५-२

सिद्धान्तकौमुदी

अथ

सिद्धान्तकौमुदी

नाम

महामहोपाध्यायश्रीभट्टोजिदीक्षितविरचिता

पाणिनीयव्याकरणसूत्रवृत्तिः ।

परवोपाह्वपाण्डुरङ्गात्मजकाशीनाथशर्मणा संशोधितः ।

भट्टोजिदीक्षितविरचितवैयाकरणसिद्धा[illegible] पा-
[illegible]मुनिप्रणीताष्टाध्यायीसूत्रपाठ-गणपाठ-[illegible]
[illegible]पाठौ, कात्यायनप्रणीतो वार्तिकपाठः, [illegible]
[illegible]नप्रणीत उणादिसूत्रपाठः, शान्तन[illegible]प्रणीतः फिट्सूत्रपाठः,
अष्टाध्यायीस्थ-धातुपाठान्तर्गत-उणादिसू[illegible]-गणसूत्राणि,
सौत्रधातवः, अष्टाध्यायीसूत्राणां [illegible] धातूनां [illegible]नां
परिभाषाणामुणादीनां फिट्सूत्राणां चाकाराद्यनुक्रमण
सूच्यश्च संगृह्यन्ते ।

येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥

ग्रन्थोऽयं

शाके १८१५ वत्सरे

मुम्बय्यां

तत्त्वविवेचकाख्ययन्त्रालये मुद्राक्षरैरङ्कितः ।

मूल्यं रूप्यकद्वयम् ।

विषयानुक्रमः ।

श्रवणं

सांकेतिकशब्दाः ।

सू = अष्टाध्यायीसूत्रपाठः ।
ग = पाणिनीयो गणपाठः ।
धा = पाणिनीयो धातुपाठः ।
प = परिभाषापाठः ।
वा = कात्यायनप्रणीतो वार्तिकपाठः ।
उ = शाकटायनप्रणीत उणादिपाठः ।
फि= शान्तनवाचार्यप्रणीत फिट्सूत्रपाठः ।
लि= पाणिनीयं लिङ्गानुशासनम् ।

॥ श्रीः ॥

वैयाकरणसिद्धान्तकौमुदी ।

मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च ।
वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥

अथ संज्ञाप्रकरणम् ।

अइउण् ।१। ऋलृक् ।२। एओङ् ।३। ऐऔच् ।४। हयवरट् ।५। [illegible]ण् ।६। ञमङणनम् ।७। झभञ् ।८। घढधष् ।९। जबगडदश् ।१०। [illegible]फछठथचटतव् ।११। कपय् ।१२। शषसर् ।१३। हल् ।१४। इति माहे-[illegible]राणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्या इतः । 'लण्'सूत्रेऽकारश्च । हकारादिष्व-[illegible]र उच्चारणार्थः ।

१ । हलन्त्यम् । १ । ३ । ३ । 'हल्' (प्र सू १४) इति सूत्रेऽन्त्यमित्स्यात् ।

२ । आदिरन्त्येन सहेता । १ । १ । ७१ । अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य संज्ञा स्यात् । इति हल्संज्ञायाम् । 'हलन्त्यम्' (सू १) । उपदेशेऽन्त्यं हलित्स्यात् । उप-[illegible] आद्योच्चारणम् । ततः 'अण्' 'अच्' इत्यादिसंज्ञासिद्धौ ।

३ । उपदेशेऽजनुनासिक इत् । १ । ३ । २ । उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । [illegible]प्रतिज्ञानुनासिक्याः पाणिनीयाः । 'लण्'(प्र सू ६)सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो [illegible]ोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । 'अनुनासिकः' इत्यादिनिर्देशात् । न ह्यत्र ककार [illegible] [illegible] 'आदिरन्त्येन-' (सू २) इत्येतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन [illegible]यन्ते ।

[illegible] ऊकालोऽज्झ्रस्वदीर्घप्लुतः । १ । २ । २७ । उश्च ऊश्च उ३श्च वः । वां काल [illegible]कालो [illegible] [illegible]च्क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ।

[illegible] उच्चैरुदात्तः । १ । २ । २९ । ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदा-[illegible]त्तः स्यात् । आ ये ।

[illegible] नीचैरनुदात्तः । १ । २ । ३० । स्पष्टम् । अर्वाङ् ।

[illegible] समाहारः स्वरितः । १ । २ । ३१ । उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मि-[illegible] स्वरितसंज्ञः स्यात् ।

[illegible] तस्यादित उदात्तमर्धह्रस्वम् । १ । २ । ३२ । ह्रस्वग्रहणमतन्त्रम् । स्वरितस्या-[illegible]मुदात्तमिति [illegible] । उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं

स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । 'क्व १ वोऽश्वाः,' 'रथानां न ये ३
शतचक्रं यो ३ ऽह्यः' इत्यादिऽवनुदात्तश्रुतिः । 'अग्निमीळे पुरोहितम्' इत्यादावुदात्तश्रु

स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ।

९ । मुखनासिकावचनोऽनुनासिकः । १ । १ । ८ । मुखसहितनासिकयोच्चार्य
वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् । अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः ।
र्णस्य द्वादश । तस्य दीर्घाभावात् । एचामपि द्वादश । तेषां ह्रस्वाभावात् ।

१० । तुल्यास्यप्रयत्नं सवर्णम् । १ । १ । ९ । ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चे
द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयश
तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासि
च । एदैतोः कण्टतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वा
लम् । नासिकानुस्वारस्य । इति स्थानानि । प्रयत्नो द्विधा । आभ्यन्तरो बाह्यश्च । आद्यश्चतुः
स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृष्टमन्तःस्थाना
विवृतमूष्मणां स्वराणां च । ह्रस्वस्यावर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमे
एतच्च सूत्रकारेण ज्ञापितम् । तथा हि ।

११ । अ अ इति । ८ । ४ । ६८ । विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य च
ध्यायीं संपूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथा च सूत्रम् ।

१२ । पूर्वत्रासिद्धम् । ८ । २ । १ । अधिकारोऽयम्, तेन सपादसप्ताध्यायीं
त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादश
विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चे

खयां यमाः खयः ᳲक ᳳपौ विसर्गः शर एव च ।
एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ॥
कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः ।
अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥

वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः ।
पलिक्क्नीः; चख्ख्नतुः, अग्ग्निः, घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः
वर्गाणां प्रथमद्वितीयाः खयः, तथा तेषामेव यमाः, जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत
विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः
तृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये (द्वितीयचतुर्थौ शलश्च) महाप्राणा इत्यर्थः ।
प्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्ताः, तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति
म् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्व
ᳲक ᳳप इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः
नुस्वारविसर्गौ । इति [स्थान] प्रयत्नविवेकः । 'ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम्'(वा १
अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते ।

१३ । नाज्झलौ । १ । १ । १० । आकारसहितोऽच् आच्, स च हल्चे

मिथः सवर्णौ न स्तः। तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न। अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात्। तथा हि।

१४। अणुदित्सवर्णस्य चाप्रत्ययः। १। १। ६९। प्रतीयते विधीयत इति प्रत्ययः, अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्राण्परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम्। अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं लकारोऽपि। एचो द्वादशानाम्। एदैतोरोदौतोश्च न मिथः सावर्ण्यम्। 'ऐऔच्' इति सूत्रारम्भसामर्थ्यात्। तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम्। 'नाज्झलौ' (सू १३) इति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव, तथापि हकारस्याकारो न सवर्णः। तत्राकारस्यापि प्रश्लिष्टत्वात्। तेन 'विश्वपाभिः' इत्यत्र 'हो ढः' (सू ३२४) इति ढत्वं न भवति। अनुनासिकाननुनासिकभेदेन यवला द्विधा। तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा।

१५। तपरस्तत्कालस्य। १। १। ७०। तः परो यस्मात्स तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्। तेन 'अत्' 'इत्' इत्यादयः षण्णां षण्णां संज्ञा। 'ऋत्' इति द्वादशानाम्।

१६। वृद्धिरादैच्। १। १। १। आदैच्च वृद्धिसंज्ञः स्यात्।

१७। अदेङ्गुणः १। १। २। अदेङ् च गुणसंज्ञः स्यात्।

१८। भूवादयो धातवः। १। ३। १। क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः।

१९। प्राग्रीश्वरान्निपाताः। १। ४। ५६। इत्यधिकृत्य।

२०। चादयोऽसत्त्वे। १। ४। ५७। अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः।

२१। प्रादयः। १। ४। ५८। अद्रव्यार्थाः प्रादयस्तथा।

२२। उपसर्गाः क्रियायोगे। १। ४। ५९।

२३। गतिश्च। १। ४। ६०। प्रादयः क्रियायोग उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः। प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप एते प्रादयः।

२४। न वेति विभाषा। १। १। ४४। निषेधविकल्पयोर्विभाषा संज्ञा स्यात्।

२५। स्वं रूपं शब्दस्याशब्दसंज्ञा। १। १। ६८। शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना।

२६। येन विधिस्तदन्तस्य। १। १। ७२। विशेषणं तदन्तस्य संज्ञा स्यात्। स्वस्य च रूपस्य। 'समासप्रत्ययविधौ प्रतिषेधः' (वा ९४५)। 'उगिद्वर्णग्रहणवर्जम्' (वा ९४६)।

२७। विरामोऽवसानम्। १। ४। ११०। वर्णानामभावोऽवसानसंज्ञः स्यात्।

२८। परः संनिकर्षः संहिता। १। ४। १०९। वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्यात्।

२९। सुप्तिङन्तं पदम्। १। ४। १४। सुबन्तं तिङन्तं च पदसंज्ञं स्यात्।

३०। हलोऽनन्तराः संयोगः। १। १। ७। अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः।

३१। ह्रस्वं लघु। १। ४। १०।

३२ । संयोगे गुरु । १ । ४ । ११ । संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ।
३३ । दीर्घं च । १ । ४ । १२ । दीर्घं च गुरुसंज्ञं स्यात् ।

इति संज्ञाप्रकरणम् ।

अथ परिभाषाप्रकरणम् ।

३४ । इको गुणवृद्धी । १ । १ । ३ । गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र 'इकः' इति षष्ठ्यन्तं पदमुपतिष्ठते ।

३५ । अचश्च । १ । २ । २८ । ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्र 'अचः' इति षष्ठ्यन्तं पदमुपतिष्ठते ।

३६ । आद्यन्तौ टकितौ । १ । १ । ४६ । टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ।

३७ । मिदचोऽन्त्यात्परः । १ । १ । ४७ । 'अचः' इति निर्धारणे षष्ठी । अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् ।

३८ । षष्ठी स्थानेयोगा । १ । १ । ४९ । अनिर्धारितसंबन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ।

३९ । स्थानेऽन्तरतमः । १ । १ । ५० । प्रसङ्गे सति सदृशतम आदेशः स्यात् । 'यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः' (प १४) ।

४० । तस्मिन्निति निर्दिष्टे पूर्वस्य । १ । १ । ६६ । सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ।

४१ । तस्मादित्युत्तरस्य । १ । १ । ६७ । पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ।

४२ । अलोऽन्त्यस्य । १ । १ । ५२ । षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ।

४३ । ङिच्च । १ । १ । ५३ । अयमप्यन्त्यस्यैव स्यात् । '–सर्वस्य'(सू ४५) इत्यस्यापवादः ।

४४ । आदेः परस्य । १ । १ । ५४ । परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । 'अलोऽन्त्यस्य' (सू ४२) इत्यस्यापवादः ।

४५ । अनेकाल्शित्सर्वस्य । १ । १ । ५५ । स्पष्टम् । 'अलोऽन्त्य'सूत्रापवादः 'अष्टाभ्य औश्' (सू ३७२) इत्यादौ 'आदेः परस्य' (सू ४४) इत्येतदपि परत्वादनेन बाध्यते ।

४६ । स्वरितेनाधिकारः । १ । ३ । ११ । स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् 'परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः' (प ३९) । 'असिद्धं बहिरङ्गमन्तरङ्गे' (प ५१) । 'अकृतव्यूहाः पाणिनीयाः' (प ५७) । निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ।

इति परिभाषाप्रकरणम् ।

अथाच्संधिप्रकरणम्।

४७। इको यणचि। ६। १। ७७। इकः स्थाने यण्स्यादचि संहितायां विषये। 'सुधी-उपास्यः' इति स्थिते। स्थानत आन्तर्यादीकारस्य यकारः। 'सुध्य्-उपास्यः' इति जाते।

४८। अनचि च। ८। ४। ४७। अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वम्।

४९। स्थानिवदादेशोऽनल्विधौ। १। १। ५६। आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ। अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य 'अनचि' (सू ४८) इति द्वित्वनिषेधो न शङ्क्यः 'अनल्विधौ' इति तन्निषेधात्।

५०। अचः परस्मिन्पूर्वविधौ। १। १। ५७। अल्विध्यर्थमिदम्। परनिमित्तोऽजादेशः स्थानिवत्स्यात् स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इति यणः स्थानिवद्भावे प्राप्ते।

५१। न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु। १। १। ५८। पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत्। इति स्थानिवद्भावनिषेधः।

५२। झलां जश्झशि। ८। ४। ५३। स्पष्टम्। इति धकारस्य दकारः।

५३। अदर्शनं लोपः। १। १। ६०। प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।

५४। संयोगान्तस्य लोपः। ८। २। २३। संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्। इति यलोपे प्राप्ते। 'यणः प्रतिषेधो वाच्यः' (वा ४८०६)। 'यणो मयो द्वे वाच्ये' (वा ५०१८)। 'मय इति पञ्चमी यण इति षष्ठी' इति पक्षे यकारस्यापि द्वित्वम्। तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि। एकधमेकयम्। द्विधं द्वियम्। द्विधमेकयम्। एकधं द्वियम्। सुद्ध्युपास्यः। मद्ध्वरिः। धात्त्रंशः। लाकृतिः।

५५। नादिन्याक्रोशे पुत्रस्य। ८। ४। ४८। पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने। पुत्रादिनी त्वमसि पापे। 'आक्रोशे' किम्। तत्त्वकथने द्विर्वचनं भवत्येव। पुत्त्रादिनी सर्पिणी। 'तत्परे च' (वा ५०२१)। पुत्रपुत्रादिनी त्वमसि पापे। 'वा हतजग्धयोः' (वा ५०२२)। पुत्रहती–पुत्त्रहती। पुत्रजग्धी–पुत्त्रजग्धी।

५६। त्रिप्रभृतिषु शाकटायनस्य। ८। ४। ५०। त्र्यादिषु वर्णेषु संयुक्तेषु वा द्वित्वम्। इन्न्द्रः–इन्द्रः। राष्ट्ट्रम्–राष्ट्रम्।

५७। सर्वत्र शाकल्यस्य। ८। ४। ५१। द्वित्वं न। अर्कः। ब्रह्मा।

५८। दीर्घादाचार्याणाम्। ८। ४। ५२। द्वित्वं न। दात्रम्। पात्रम्।

५९। अचो रहाभ्यां द्वे। ८। ४। ४६। अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। हर्य्यनुभवः। नह्य्यस्ति।

६०। हलो यमां यमि लोपः। ८। ४। ६४। हलः परस्य यमो लोपः स्याद्वा यमि। इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम्। लोपारम्भफलं तु 'आदित्यो देवतास्येत्यादित्यं हविः' इत्यादौ। 'यमां यमि' इति यथासंख्यविज्ञानान्नेह। माहात्म्यम्। तादात्म्यम्।

६१ । एचोऽयवायावः । ६ । १ । ७८ । एचः क्रमादय् अव् आय् आव् एते स्युरचि ।

६२ । तस्य लोपः । १ । ३ । ९ । तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं चेत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ।

६३ । वान्तो यि प्रत्यये । ६ । १ । ७९ । यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । 'गोपयसोर्यत्' (सू १५३८) । नावा तार्यं नाव्यम् । 'नौवयोधर्म-' (सू १६४३) इत्यादिना यत् । 'गोर्यूतौ छन्दस्युपसंख्यानम्' (वा ३५४३) । 'अध्वपरिमाणे च' (वा ३५४४) । गव्यूतिः । 'ऊतियूति-' (सू ३२७४) इत्यादिना यूतिशब्दो निपातितः । 'वान्तः' इत्यत्र वकाराद् 'गोर्यूतौ' इत्यत्र छकाराद्वा पूर्वभागे 'लोपो व्योः-' (सू ८७३) इति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ।

६४ । धातोस्तन्निमित्तस्यैव । ६ । १ । ८० । यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव । लव्यम् । अवश्यलाव्यम् । 'तन्निमित्तस्यैव' इति किम् । ओयते औयत ।

६५ । क्षय्यजय्यौ शक्यार्थे । ६ । १ । ८१ । यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । 'शक्यार्थे' किम् । क्षेतुं जेतुं योग्यं क्षेयं पापं जेयं मनः ।

६६ । क्रय्यस्तदर्थे । ६ । १ । ८२ । तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्यापणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ।

६७ । लोपः शाकल्यस्य । ८ । ३ । १९ । अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे । 'पूर्वत्रासिद्धम्' (सू १२) इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसंधिः । हर एहि-हरयेहि । विष्ण इह-विष्णविह । श्रिया उद्यतः-श्रियायुद्यतः । गुरा उत्कः-गुरावुत्कः । 'कानि सन्ति' 'कौ स्तः' इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ 'न पदान्त-' (सू ५१) इति सूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ।

६८ । एकः पूर्वपरयोः । ६ । १ । ८४ । इत्यधिकृत्य ।

६९ । आद्गुणः । ६ । १ । ८७ । अवर्णादचि परे पूर्वपरयोरेको गुणादेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ।

७० । उरण्रपरः । १ । १ । ५१ । 'ऋ इति त्रिंशतः संज्ञा' इत्युक्तम्, तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् 'कृष्णर्द्धिः' इत्यत्रार् । 'तवल्कारः' इत्यत्राल् । 'अचो रहाभ्याम्-' (सू ५९) इति पक्षे द्वित्वम् ।

७१ । झरो झरि सवर्णे । ८ । ४ । ६५ । हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे, द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णार्धिः-कृष्णर्द्धिः-कृष्णर्द्द्धिः । 'यण इति पञ्चमी मय इति षष्ठी' इति पक्षे ककारस्य द्वित्वम् । लस्य तु 'अनचि च' (सू ४८) इति । तेन 'तवल्कारः' इत्यत्र रूपचतुष्टयम् ।

द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि ।
तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥

७२ । वृद्धिरेचि । ६ । १ । ८८ । आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ।

७३ । एत्येधत्यूठ्सु । ६ । १ । ८९ । अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । 'एजाद्योः' किम् । उपेतः । मा भवान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः 'एङि पररूपम्' (सू ७८) इत्यस्यैव बाधिका । न तु 'ओमाङोश्च' (सू ८०) इत्यस्य । तेन 'अवैहि' इति वृद्धिरसाधुरेव । 'अक्षादूहिन्यामुपसंख्यानम्' (वा ३६०४) । अक्षौहिणी सेना । 'स्वादीरेरिणोः' (वा ३६०६) । स्वैरः । स्वैरीरितुं शीलमस्येति स्वैरी । स्वैरिणी । 'प्रादूहोढोढ्येषैष्येषु' (वा ३६०५) । प्रौहः । प्रौढः । 'अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्' (प १५) । 'व्रश्च–' (सू २९४) इति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् । तेनोढग्रहणेन क्तान्तमेव गृह्यते । न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः । 'इष् इच्छायां तुदादिः,' 'इष् गतौ दिवादिः,' 'इष् आभीक्ष्ण्ये क्र्यादिः,' एषां घञि ण्यति च 'एषः' 'एष्यः' इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः । यस्तु 'ईष् उञ्छे' यश्च 'ईष् गतिहिंसादर्शनेषु' तयोर्दीर्घोपधत्वात् ईषः । ईष्यः । तत्राद्गुणे प्रेषः । प्रेष्यः । 'ऋते च तृतीयासमासे' (वा० ३६०७) । सुखेन ऋतः सुखार्तः । 'तृतीया' इति किम् । परमर्तः । 'प्रवत्सतरकम्बलवसनार्णदशानामृणे' (वा० ३६०८–९) । प्रार्णम् । वत्सतरार्णमित्यादि । ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ।

७४ । उपसर्गादृति धातौ । ६ । १ । ९१ । अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ।

७५ । अन्तादिवच्च । ६ । १ । ८५ । योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ।

७६ । खरवसानयोर्विसर्जनीयः । ८ । ३ । १५ । खर्यवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । 'उभयथर्क्षु' (सू ३६३०), 'कर्तरि चर्षिदेवतयोः' (सू ३१६७) इत्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे 'धातौ' इति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन 'ऋत्यकः' (सू ९२) इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ।

७७ । वा सुप्यापिशलेः । ६ । १ । ९२ । अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति–प्रर्षभीयति । सावर्ण्याॢ्लवर्णस्य ग्रहणम् । प्राल्कारीयति–प्रल्कारीयति । तपरत्वाद्दीर्घे न । उप ॠकारीयति–उपर्कारीयति ।

७८ । एङि पररूपम् । ६ । १ । ९४ । आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह 'वा सुपि' इत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनैङादौ सुब्धातौ वा । उपेडकीयति–उपैडकीयति । प्रोघीयति–प्रौघीयति । 'एवे चानियोगे' (वा ३६३१) । नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवक्लृप्तावेवशब्दः । 'अनियोगे' किम् । तवैव ।

७९ । अचोऽन्त्यादि टि । १ । १ । ६४ । अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टि-

संज्ञं स्यात् । 'शकन्ध्वादिषु पररूपं वाच्यम्' (वा ३६३२) । तच्च टेः । शकन्धुः । कर्कन्धुः । कुलटा । 'सीमन्तः केशवेशे' (वा ३६३३)। सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः। 'सारङ्गः पशुपक्षिणोः' (ग १३६) । साराङ्गोऽन्यः । आकृतिगणोऽयम् । मार्तण्डः । स्थूलोतुः–स्थूलौतुः । बिम्बोष्ठः–बिम्बौष्ठः । 'ओत्वोष्ठयोः समासे वा' (वा ३६३४) । 'समासे' किम् । तवौष्ठः ।

८० । ओमाङोश्च । ६ । १ । ९५ । ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि–शिवेहि ।

८१ । अव्यक्तानुकरणस्यात इतौ । ६ । १ । ९८ । ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ परे पररूपमेकादेशः स्यात् । पटत् इति पटिति । 'एकाचो न' (वा ३६३७)। श्रदिति ।

८२ । नाम्रेडितस्यान्त्यस्य तु वा । ६ । १ । ९९ । आम्रेडितस्य प्रागुक्तं न स्यात् । अन्त्यस्य तु तकारमात्रस्य वा स्यात् । 'डाचि बहुलं द्वे भवतः' (वा ४६९७) । इति बहुलवचनाद्द्वित्वम् ।

८३ । तस्य परमाम्रेडितम् । ८ । १ । २ । द्विरुक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ।

८४ । झलां जशोऽन्ते । ८ । २ । ३९ । पदान्ते झलां जशः स्युः । पटत्पटादिति ।

८५ । अकः सवर्णे दीर्घः । ६ । १ । १०१ । अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । 'अचि' किम् । कुमारी शेते । 'नाज्झलौ' (सू १३) इति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । 'अकः' किम् । हरये । 'अकोऽकि दीर्घः' इत्येव सुवचम् । 'ऋति सवर्णे ऋ वा' (वा ३६४०) । होतृकारः–होतॄकारः [–होतृऋकारः–होतृ३कारः] । 'लृति सवर्णे ऌ वा' (वा ३६४१) । होतॢकारः [–होतृलकारः–होतॢ३कारः] । पक्षे ऋकारः सावर्ण्यात् । होतॄकारः । 'ऋति ऋ वा' 'लृति ऌ वा' इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्राभितोऽभक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ, शेषं प्राग्वत् । इहोभयत्रापि 'ऋत्यकः' (सू ९२) इति पाक्षिकः प्रकृतिभावो वक्ष्यते ।

८६ । एङः पदान्तादति । ६ । १ । १०९ । पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ।

८७ । सर्वत्र विभाषा गोः । ६ । १ । १२२ । लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गोअग्रम्–गोऽग्रम् । 'एङन्तस्य' किम् । चित्रग्वग्रम् । 'पदान्ते' किम् । गोः ।

८८ । अवङ् स्फोटायनस्य । ६ । १ । १२३ । 'अति' इति निवृत्तम् । अचि पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । 'पदान्ते' किम् । गवि । व्यवस्थितविभाषा गवाक्षः ।

८९ । इन्द्रे च । ६ । १ । १२४ । गोरवङ् स्यादिन्द्रे । गवेन्द्रः ।

अथ प्रकृतिभावः ।

९० । प्लुतप्रगृह्या अचि नित्यम् । ६ । १ । १२५ । प्लुताः प्रगृह्याश्च वक्ष्यन्ते, तेऽचि परे नित्यं प्रकृत्या स्युः । एहि कृष्ण३ अत्र गौश्चरति । हरी एतौ । 'नित्यम्' इति किम् । 'हरी एतौ' इत्यादावयमेव प्रकृतिभावो यथा स्यात्, 'इकोऽसवर्णे–' (सू ९१) इति ह्रस्वसमुच्चितो मा भूत् ।

९१ । इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । ६ । १ । १२७ । पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र 'ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारो न कर्तव्यः' इति भाष्ये स्थितम् । चक्रि अत्र–चक्र्यत्र । 'पदान्ताः' इति किम् । गौर्यौ । 'न समासे' (वा ३६८४) । वाप्यश्वः । 'सिति च' (वा ३६८४) । पार्श्वम् ।

९२ । ऋत्यकः । ६ । १ । १२८ । ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः–ब्रह्मर्षिः । 'पदान्ताः' इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्त ऋषीणाम्–सप्तर्षीणाम् ।

९३ । वाक्यस्य टेः प्लुत उदात्तः । ८ । २ । ८२ । इत्यधिकृत्य ।

९४ । प्रत्यभिवादेऽशूद्रे । ८ । २ । ८३ । अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् । स चोदात्तः । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्त३ । 'स्त्रियां न' (वा ४८६४) । अभिवादये गार्ग्यहम् । भो आयुष्मती भव गार्गि । नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि । 'भोराजन्यविशां वेति वाच्यम्' (वा ४८६५) । आयुष्मानेधि भो३ः । आयुष्मानेधीन्द्रवर्म३न् । आयुष्मानेधीन्द्रपालित३ ।

९५ । दूराद्धूते च । ८ । २ । ८४ । दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त३ ।

९६ । हैहेप्रयोगे हैहयोः । ८ । २ । ८५ । एतयोः प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे३ राम । राम है३ ।

९७ । गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् । ८ । २ । ८६ । दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे३वदत्त । देवद३त्त । देवदत्त३ । 'गुरोः' किम् । वकारात्परस्याकारस्य मा भूत् । 'अनृतः' किम् । कृष्ण३ । एकैकग्रहणं पर्यायार्थम् । इह 'प्राचाम्' इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ।

९८ । अप्लुतवदुपस्थिते । ६ । १ । १२९ । उपस्थितोऽनार्ष इतिशब्दः, तस्मिन्परे प्लुतोऽप्लुतवद्भवति अप्लुतकार्यं यणादिकं करोति । सुश्लोक३ इति–सुश्लोकेति । 'वत्' किम् । अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात् । अग्नी३ इति ।

९९ । इ३ चाक्रवर्मणस्य । ६ । १ । १३० । इ३कारः प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुहि३ इति–चिनुहीति । चिनुहि३ इदम्–चिनुहीदम् । उभयत्रविभाषेयम् ।

१०० । ईदूदेद्द्विवचनं प्रगृह्यम् । १ । १ । ११ । ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । 'मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम' इत्यत्र त्विवार्थे वशब्दो वाशब्दो वा बोध्यः ।

१०१। अदसो मात्। १। १। १२। अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। 'मात्' किम्। अमुकेऽत्र। असति माद्ग्रहण एकारोऽप्यनुवर्तेत।

१०२। शे। १। १। १३। अयं प्रगृह्यः स्यात्। अस्मे इन्द्राबृहस्पती।

१०३। निपात एकाजनाङ्। १। १। १४। एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात्। अ अवद्यम्। इ वितर्के। उ विस्मये। इ इन्द्रः। उ उमेशः। 'अनाङ्' इत्युक्तेरङिदाकारः प्रगृह्य एव। आ एवं नु मन्यसे। आ एवं किल तत्। ङित्तु न प्रगृह्यः। ईषदुष्णम्। ओष्णम्। 'वाक्यस्मरणयोरङित्। अन्यत्र ङित्' इति विवेकः।

१०४। ओत्। १। १। १५। ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः।

१०५। संबुद्धौ शाकल्यस्येतावनार्षे। १। १। १६। संबुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिक इतौ परे। विष्णो इति–विष्ण इति–विष्णविति। 'अनार्षे' इति किम्। ब्रह्मबन्धवित्यब्रवीत्।

१०६। उञः। १। १। १७। उञ इतौ वा प्रागुक्तम्। उ इति–विति।

१०७। ऊँ। १। १। १८। उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात्। ऊँ इति–विति।

१०८। मय उञो वो वा। ८। ३। ३३। मयः परस्य उञो वो वा स्यादचि। किमु उक्तम्–किम्वुक्तम्। वस्यासिद्धत्वान्नानुस्वारः।

१०९। ईदूतौ च सप्तम्यर्थे। १। १। १९। सतम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात्। सोमो गौरी अधि श्रितः। मामकी तनू इति। 'सुपां सुलुक्–' (सू. ३५६१) इति सप्तम्या लुक्। अर्थग्रहणं किम्। वृत्तावर्थान्तरोपसंक्रान्ते मा भूत्। वाप्यामश्वो वाप्यश्वः।

११०। अणोऽप्रगृह्यस्यानुनासिकः। ८। ४। ५७। अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात्। दधिँ–दधि। 'अप्रगृह्यस्य' किम्। अग्नी।

इत्यच्संधिप्रकरणम्।

अथ हल्संधिप्रकरणम्।

१११। स्तोः श्चुना श्चुः। ८। ४। ४०। सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। हरिश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय।

११२। शात्। ८। ४। ४४। शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः।

११३। ष्टुना ष्टुः। ८। ४। ४१। स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे।

११४। न पदान्ताट्टोरनाम्। ८। ४। ४२। 'अनाम्' इति लुप्तषष्ठीकं पदम्। पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। 'पदान्तात्' किम्। ईट्टे। 'टोः' किम्। सर्पिष्टमम्। 'अनाम्नवतिनगरीणामिति वाच्यम्' (वा ५०१६)। षण्णाम्। षण्णवतिः। षण्णगर्यः।

११५। तोः षि। ८। ४। ४३। तवर्गस्य षकारे परे न ष्टुत्वम्। सन्षष्ठः। 'झलां जशोऽन्ते' (सू. ८४)। वागीशः। चिद्रूपम्।

११६ । यरोऽनुनासिकेऽनुनासिको वा । ८ । ४ । ४५ । यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः–एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः । 'प्रत्यये भाषायां नित्यम्' (वा ५०१७) । तन्मात्रम् । चिन्मयम् । कथं तर्हि 'मदोदग्राः ककुद्मन्तः' इति । यवादि(ग २९०)गणे दकारनिपातनात् ।

११७ । तोर्लि । ८ । ४ । ६० । तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाल्लिँखति । नकारस्यानुनासिको लकारः ।

११८ । उदः स्थास्तम्भोः पूर्वस्य । ८ । ४ । ६१ । उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् । 'आदेः परस्य' (सू ४४) । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य महाप्राणस्य सस्य तादृश एव थकारः । तस्य 'झरो झरि–' (सू ७१) इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणम् । न तु 'खरि च' (सू १२१) इति चर्त्वम् । चर्त्वं प्रति थकारस्यासिद्धत्वात् ।

११९ । झयो होऽन्यतरस्याम् । ८ । ४ । ६२ । झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थ एवादेशः । वाग्घरिः– वाग्हरिः ।

१२० । शश्छोऽटि । ८ । ४ । ६३ । पदान्ताज्झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ।

१२१ । खरि च । ८ । ४ । ५५ । खरि झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः–तच्शिवः । 'छत्वममीति वाच्यम्' (वा ५०२५) । तच्छ्लोकेन–तच्श्लोकेन । 'अमि' किम् । वाक् श्च्योतति ।

१२२ । मोऽनुस्वारः । ८ । ३ । २३ । मान्तस्य पदस्यानुस्वारः स्याद्धलि । 'अलोऽन्त्यस्य' (सू ४२) । हरिं वन्दे । 'पदस्य' इति किम् । गम्यते ।

१२३ । नश्चापदान्तस्य झलि । ८ । ३ । २४ । नस्य मस्य चापदान्तस्य झल्यनुस्वारः । यशांसि । आक्रंस्यते । 'झलि' किम् । मन्यते ।

१२४ । अनुस्वारस्य ययि परसवर्णः । ८ । ४ । ५८ । स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । 'कुर्वन्ति' इत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ।

१२५ । वा पदान्तस्य । ८ । ४ । ५९ । पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि–त्वं करोषि । संय्यँन्ता–संयन्ता । सव्ँवत्सरः–संवत्सरः । यँल्लोकम्–यं लोकम् । अत्रानुस्वारस्य पक्षेऽनुनासिका यवलाः ।

१२६ । मो राजि समः क्वौ । ८ । ३ । २५ । क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ।

१२७ । हे मपरे वा । ८ । ३ । २६ । मपरे हकारे परे मस्य म एव स्याद्वा । 'ह्मल् ह्मल् चलने' । किम् ह्मलयति–किं ह्मलयति । 'यवलपरे यवला वेति वक्तव्यम्' (वा ४९०२)

१२८ । यथासंख्यमनुदेशः समानाम् । १ । ३ । १० । समसंबन्धी विधिर्यथासंख्यं

स्यात्। किँय्ँ ह्यः-किं ह्यः। किँव्ँ ह्वलयति-किं ह्वलयति। किँल्ँ ह्लादयति-किं ह्लादयति।
१२९। नपरे नः।८।३।२७। नपरे हकारे परे मस्य नः स्याद्वा। किन्ँ ह्नुते-किं ह्नुते।
१३०। ङ्णोः कुक्टुक्शरि।८।३।२८। ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि। कुक्टुकोरसिद्धत्वाज्जश्त्वं न। 'चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्' (वा ५०२३)। प्राङ्ख्षष्ठः-प्राङ्क्षष्ठः-प्राङ् षष्ठः। सुगण्ठ्षष्ठः-सुगण्ट्षष्ठः-सुगण्षष्ठः।
१३१। डः सि धुट्।८।३।२९। डात्परस्य सस्य धुड्वा स्यात्। षट्त्सन्तः-षट्सन्तः।
१३२। नश्च।८।३।३०। नकारान्तात्सस्य धुड्वा स्यात्। सन्त्सः-सन्सः।
१३३। शि तुक्।८।३।३१। नस्य पदान्तस्य शे परे तुग्वा स्यात्। 'शश्छोऽटि' (सू १२०) इति छत्वविकल्पः। पक्षे 'झरो झरि-' (सू ७१) इति चलोपः। सञ्छंभुः-सञ्च्छंभुः-सञ्चशंभुः-सञ्शंभुः।

अच्छौ अचछा अचशा अशाविति चतुष्टयम्।
रूपाणामिह तुक्छत्वचलोपानां विकल्पनात्॥

१३४। ङमो ह्रस्वादचि ङमुण्नित्यम्।८।३।३२। ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुडागमः स्यात्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः।
१३५। समः सुटि।८।३।५। समो रुः स्यात्सुटि। 'अलोऽन्त्यस्य' (सू ४२)।
१३६। अत्रानुनासिकः पूर्वस्य तु वा।८।३।२। अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा स्यात्।
१३७। अनुनासिकात्परोऽनुस्वारः।८।३।४। अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात्। 'खरवसानयोर्विसर्जनीयः' (सू ७६)।
१३८। विसर्जनीयस्य सः।८।३।३४। खरि विसर्जनीयस्य सः स्यात्। एतदपवादेन 'वा शरि' (सू १५१) इति पाक्षिके विसर्गे प्राप्ते। 'संपुंकानां सो वक्तव्यः' (वा४८९२)। सँस्स्कर्ता-संस्स्कर्ता। 'समो वा लोपमेके' इति भाष्यम्। लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयम्। द्विसकारं तूक्तमेव। तत्र 'अनचि च' (सू ४८) इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम्। अनुस्वारविसर्गजिह्वामूलीयोपध्मानीययमानामकारोपरि शर्षु च पाठस्योपसंख्यातत्वेनानुस्वारस्याप्यच्त्वात्। अनुनासिकवतां त्रयाणां 'शरः खयः' (वा ५०१९) इति कद्वित्वे षट्। अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश। एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति चतुःपञ्चाशत्। अणोऽनुनासिकत्वेऽष्टोत्तरं शतम्।
१३९। पुमः खय्यम्परे।८।३।६। अम्परे खयि पुम्शब्दस्य रुः स्यात्। व्युत्पत्तिपक्षे 'अप्रत्ययस्य' (सू १५९) इति षत्वपर्युदासात् ऽकऽपयोः प्राप्तौ। अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ। 'संपुंकानाम्-' (वा ४८९२) इति सः। पुँस्कोकिलः-पुंस्कोकिलः। पुँस्पुत्रः-पुंस्पुत्रः। 'अम्परे' किम्। पुंक्षीरम्। 'खयि' किम्। पुंदासः। 'ख्याञादेशे न' (वा १९९१)। पुंख्यानम्।
१४०। नश्छव्यप्रशान्।८।३।७। अम्परे छवि नकारान्तस्य पदस्य रुः स्यात्।

न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्चुत्वम् । शार्ङ्गिँश्छिन्धि–शार्ङ्गिंश्छिन्धि । चक्रिँस्त्रायस्व–चक्रिंस्त्रायस्व । 'पदस्य' किम् । हन्ति । 'अम्परे' किम् । सन्त्सरुः खड्गमुष्टिः । 'अप्रशान्' किम् । प्रशान्तनोति ।

१४१ । नॄन्पे । ८ । ३ । १० । 'नॄन्' इत्यस्य रुः स्याद्वा पकारे परे ।

१४२ । कुप्वोः ᳵकᳶपौ च । ८ । ३ । ३७ । कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्तिन्यायेन 'विसर्जनीयस्य सः' (सू १३८) इत्यस्यापवादोऽयम् । न तु 'शर्परे विसर्जनीयः' (सू १५०) इत्यस्य । तेन 'वासः क्षौमम्' इत्यादौ विसर्ग एव । नॄँᳶपाहि–नॄंᳶपाहि–नॄँः पाहि–नॄंः पाहि–नॄन्पाहि ।

१४३ । कानाम्रेडिते । ८ । ३ । १२ । कान्नकारस्य रुः स्यादाम्रेडिते परे । 'संपुंकानाम्–' (वा ४८९२) इति सः । यद्वा ।

१४४ । कस्कादिषु च । ८ । ३ । ४८ । ᳵकᳶपयोरपवादः । एष्विण उत्तरस्य विसर्गस्य षः स्यात् । अन्यस्य तु सः । काँस्कान्–कांस्कान् । कस्कः । कौतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ।

१४५ । संहितायाम् । ६ । १ । ७२ । इत्यधिकृत्य ।

१४६ । छे च । ६ । १ । ७३ । ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाज्जश्त्वेन दः । ततश्चर्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वेन जः । तस्य चर्त्वेन चः । श्चुत्वस्यासिद्धत्वात् 'चोः कुः' (सू ३७८) इति कुत्वं न । स्वच्छाया । शिवच्छाया ।

१४७ । आङ्माङोश्च । ६ । १ । ७४ । एतयोश्छे परे तुक्स्यात् । 'पदान्ताद्वा' (सू १४९) इति विकल्पापवादः । आच्छादयति । माच्छिदत् ।

१४८ । दीर्घात् । ६ । १ । ७५ । दीर्घाच्छे परे तुक्स्यात् । दीर्घस्यायं तुक्, न तु ह्रस्वस्य । '–सेनासुराच्छाया–' (सू ८२८) इति ज्ञापकात् । चेच्छिद्यते ।

१४९ । पदान्ताद्वा । ६ । १ । ७६ । दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया–लक्ष्मीछाया ।

इति हल्संधिप्रकरणम् ।

अथ विसर्गसंधिप्रकरणम् ।

'विसर्जनीयस्य सः' (सू १३८) । विष्णुस्त्राता ।

१५० । शर्परे विसर्जनीयः । ८ । ३ । ३५ । शर्परे खरि विसर्जनीयस्य विसर्जनीयः । न त्वन्यत् । कः त्सरुः । 'घनाघनः क्षोभणः' । इह यथायथं सत्वं जिह्वामूलीयश्च न ।

१५१ । वा शरि । ८ । ३ । ३६ । शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते–हरिश्शेते । 'खर्परे शरि वा विसर्गलोपो वक्तव्यः' (वा ४५०६) । राम स्थाता–रामः स्थाता । हरि स्फुरति–हरिः स्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् । 'कुप्वोः ᳵकᳶपौ च' (सू १४२) । कᳵ करोति–कः करोति । कᳵ खनति–कः खनति । कᳶ पचति–कः पचति । कᳶ फलति–कः फलति ।

१५२ । सोऽपदादौ । ८ । ३ । ३८ । विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ।

'पाशकल्पककाम्येष्विति वाच्यम्' (वा ५०३३) । पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति । 'अनव्ययस्येति वाच्यम्' (वा ४९०१) । प्रातःकल्पम् । 'काम्ये रोरेवेति वाच्यम्' (वा ४९०२) । नेह । गीःकाम्यति ।

१९३ । इणः षः । ८ । ३ । ३९ । इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ।

१९४ । नमस्पुरसोर्गत्योः । ८ । ३ । ४० । गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषया गतिसंज्ञा । तदभावे नमः करोति । 'पुरोऽव्ययम्' (सू ७६८) इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रविष्टव्याः ।

१९५ । इदुदुपधस्य चाप्रत्ययस्य । ८ । ३ । ४१ । इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । 'अप्रत्ययस्य' किम् । अग्निः करोति । वायुः करोति । 'एकादेशशास्त्रनिमित्तकस्य न षत्वम् । कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात्' (वा ४९१५) । तेनेह न । मातुः कृपा । 'मुहुसः प्रतिषेधः' (वा ४९११) । मुहुःकामा ।

१९६ । तिरसोऽन्यतरस्याम् । ८ । ३ । ४२ । तिरसः सो वा स्यात्कुप्वोः । तिरस्कर्ता-तिरःकर्ता ।

१९७ । द्विस्त्रिश्चतुरिति कृत्वोऽर्थे । ८ । ३ । ४३ । कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात्कुप्वोः । द्विष्करोति-द्विः करोति इत्यादि । 'कृत्वोऽर्थे' किम् । चतुष्कपालः ।

१९८ । इसुसोः सामर्थ्ये । ८ । ३ । ४४ । एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति-सर्पिः करोति । धनुष्करोति-धनुः करोति । सामर्थ्यमिह व्यपेक्षा । 'सामर्थ्ये' किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ।

१९९ । नित्यं समासेऽनुत्तरपदस्थस्य । ८ । ३ । ४५ । इसुसोर्विसर्गस्यानुत्तरपदस्थस्य समासे नित्यं षः स्यात्कुप्वोः परयोः । सर्पिष्कुण्डिका । 'अनुत्तरपदस्थस्य' इति किम् । परमसर्पिःकुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थो व्यपेक्षायां नित्यार्थश्च ।

१६० । अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । ८ । ३ । ४६ । अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशायस्कुशा । अयस्कर्णी । 'अतः' किम् । गीःकारः । 'अनव्ययस्य' किम् । स्वःकामः । 'समासे' किम् । यशः करोति । 'अनुत्तरपदस्थस्य' किम् । परमयशःकारः ।

१६१ । अधःशिरसी पदे । ८ । ३ । ४७ । एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधः पदम् । शिरः पदम् । अनुत्तरपदस्थस्येत्येव । परमशिरःपदम् । कस्कादिषु च । भास्करः ।

इति विसर्गसंधिप्रकरणम् ।

अथ स्वादिसंधिप्रकरणम् ।

'स्वौजसमौट्–' (सू १८३) इति सुप्रत्यये 'शिवस् अर्च्यः' इति स्थिते ।

१६२ । ससजुषो रुः । ८ । २ । ६६ । पदान्तस्य सस्य 'सजुष्'शब्दस्य च रुः स्यात् । जश्त्वापवादः ।

१६३ । अतो रोरप्लुतादप्लुते । ६ । १ । ११३ । अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । 'भोभगोअघो–' (सू १६७) इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्योत्वविधेः सामर्थ्यात् ।

१६४ । प्रथमयोः पूर्वसवर्णः । ६ । १ । १०२ । अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ।

१६५ । नादिचि । ६ । १ । १०४ । अवर्णादिचि परे न पूर्वसवर्णदीर्घः । 'आद्गुणः' (सू ६९) । 'एङः पदान्तादति' (सू ८६) । शिवोऽर्च्यः । 'अतः' इति तपरः किम् । देवा अत्र । 'अति' इति तपरः किम् । श्व आगन्ता । 'अप्लुतात्' किम् । एहि सुस्रोत३ अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । 'अप्लुतात्' इति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् । 'अप्लुते' इति किम् । तिष्ठतु पय अ३ग्निदत्त । 'गुरोरनृतः–'(सू ९७) इति प्लुतः ।

१६६ । हशि च । ६ । १ । ११४ । अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । 'रोः' इत्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । ध्मातर्गच्छ । 'देवास् इह' इति स्थिते । रुत्वम् ।

१६७ । भोभगोअघोअपूर्वस्य योऽशि । ८ । ३ । १७ । एतत्पूर्वस्य रोर्यादेशः स्यादशि परे । असंधिः सौत्रः । 'लोपः शाकल्यस्य' (सू ६७) । देवा इह–देवायिह । 'अशि' किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते, तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । न ह्ययमल्विधिः । 'रोः' इति समुदायरूपाश्रयणात् । भोस्, भगोस्, अघोस्, इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ।

१६८ । व्योर्लघुप्रयत्नतरः शाकटायनस्य । ८ । ३ । १८ । पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ।

१६९ । ओतो गार्ग्यस्य । ८ । ३ । २० । ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्ग्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । 'पदान्तस्य' किम् । तोयम् ।

१७० । उञि च पदे । ८ । ३ । २१ । अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि परे । स उ एकाग्निः । 'पदे' किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते, तर्ह्युत्तरार्थं पदग्रहणम् ।

१७१ । हलि सर्वेषाम् । ८ । ३ । २२ । भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । 'हलि' किम् । देवायिह–देवा इह ।

१७२ । रोऽसुपि । ८ । २ । ६९ । अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अह-

रहः। अहर्गणः । 'असुपि' किम्। अहोभ्याम् । अत्र 'अहन्' (सू ४४३) इति रुत्वम् 'रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्' (वा४८४७)। अहोरूपम् । गतमहो रात्रिरेषा । एकदेश विकृतस्यानन्यत्वादहोरात्रः। अहोरथन्तरम् । 'अहरादीनां पत्यादिषु वा रेफः (वा४८९१) विसर्गापवादः। अहर्पतिः। गीर्पतिः। धूर्पतिः। पक्षे विसर्गोपध्मानीयौ।

१७३। रो रि। ८। ३। १४। रेफस्य रेफे परे लोपः स्यात्।

१७४। ढ्रलोपे पूर्वस्य दीर्घोऽणः। ६। ३। १११। ढरेफौ लोपयतीति तथा, तस्मिन्वर्णेऽर्थाड्ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात्। पुना रमते। हरी रम्यः। शंभू राजते। 'अणः' किम्। तृढः। वृढः। 'तृहू हिंसायाम्'। 'वृहू उद्यमने'। पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्यैव दीर्घार्थम्। अजर्घाः। लीढः। 'मनस् रथः' इत्यत्र रुत्वे कृते 'हशि च' (सू १६६) इत्युत्वे 'रो रि' (सू १७३) इति लोपे च प्राप्ते।

१७५। विप्रतिषेधे परं कार्यम्। १। ४। २। तुल्यबलविरोधे सति परं कार्यं स्यात्। इति लोपे प्राप्ते। 'पूर्वत्रासिद्धम्' (सू १२) इति 'रो रि' (सू १७३) इत्यस्यासिद्धत्वादुत्वमेव। मनोरथः।

१७६। एतत्तदोः सुलोपोऽकोरनञ्समासे हलि। ६। १। १३२। अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे। एष विष्णुः। स शंभुः। 'अकोः' किम् एषको [illegible]ः। 'अनञ्समासे' किम्। असः शिवः। 'हलि' किम्। एषोऽत्र।

१७७। सोऽचि लोपे चेत्पादपूरणम्। ६। १। १३४। 'सस्' इत्येतस्य सोर्लोप स्यादचि पादश्चेल्लोपे सत्येव पूर्येत। 'सेमामविड्ढि प्रभृतिम्'। इह 'ऋक्पाद एव गृह्यते' इति वामनः। 'अविशेषाच्छ्लोकपादोऽपि' इत्यपरे। 'सैष दाशरथी रामः'। 'लोपे चेत्' इति किम्। स इत्क्षेति। 'स एवमुक्त्वा'। 'सत्येव' इत्यवधारणं तु 'स्यश्छन्दसि बहुलम्' (सू ३५२६) इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते। तेनेह न। 'सोऽहमाजन्मशुद्धानाम्'

इति स्वादिसंधिप्रकरणम्।

अथाजन्तपुंलिङ्गप्रकरणम्।

१७८। अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। १। २। ४५। धातुं प्रत्ययं प्रत्य नान्तं च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्।

१७९। कृत्तद्धितसमासाश्च। १। २। ४६। कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः। पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम्। यत्र संघाते पूर्वो भागः पदं तत्चेद्भवति तर्हि समासस्यैव। तेन वाक्यस्य न।

१८०। प्रत्ययः। ३। १। १। आ पञ्चमपरिसमाप्तेरधिकारोऽयम्।

१८१। परश्च। ३। १। २। अयमपि तथा।

१८२। ङ्याप्प्रातिपदिकात्। ४। १। १। ङ्यन्तादाबन्तात्प्रातिपदिकाच्चेत्या पञ्चमपरिसमाप्तेरधिकारः। 'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (प ७२) इत्ये सिद्धे ङ्याब्ग्रहणं ङ्याबन्तात्तद्धितोत्पत्तिर्यथा स्यान्ङ्याब्भ्यां प्राङ्मा भूदित्येवमर्थम्।

१८३। स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

४।१।२। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङस्योरुकारेकारौ जशटङपाश्चेतः ।

१८४। विभक्तिश्च ।१।४।१०४। सुप्तिङौ विभक्तिसंज्ञौ स्तः । तत्र 'सु' 'औ' 'जस्' इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञाः । ताभिरिहापि व्यवहारः ।

१८५। सुपः ।१।४।१०३। सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ।

१८६। द्व्येकयोर्द्विवचनैकवचने ।१।४।२२। द्वित्वैकत्वयोरेतौ स्तः ।

१८७। बहुषु बहुवचनम् ।१।४।२१। बहुत्व एतत्स्यात् । रुत्वविसर्गौ । रामः ।

१८८। सरूपाणामेकशेष एकविभक्तौ ।१।२।६४। एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते । 'प्रथमयोः पूर्वसवर्णः' (सू १६४) । 'नादिचि' (सू १६५) । 'वृद्धिरेचि' (सू ७२) । रामौ ।

१८९। चुटू ।१।३।७। प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ।

१९०। न विभक्तौ तुस्माः ।१।३।४। विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्त्वम् ।

१९१। अतो गुणे ।६।१।९७। अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । 'अतो गुणे' (सू १९१) इति हि 'पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्' (प ६०) इति न्यायेन 'अकः सवर्णे दीर्घः' (सू ८५) इत्यस्यैवापवादः । न तु 'प्रथमयोः—' (सू १६४) इत्यस्यापि । रामाः ।

१९२। एकवचनं संबुद्धिः ।२।३।४९। संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ।

१९३। एङ्ह्रस्वात्संबुद्धेः ।६।१।६९। एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । 'एङ्'ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ।

१९४। अमि पूर्वः ।६।१।१०७। अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ।

१९५। लशक्वतद्धिते ।१।३।८। तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ।

१९६। तस्माच्छसो नः पुंसि ।६।१।१०३। पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य नः स्यात्पुंसि ।

१९७। अट्कुप्वाङ्नुम्व्यवायेऽपि ।८।४।२। अट् कवर्गः पवर्गः आङ् नुम् चैतैर्व्यस्तैर्यथासंभवमिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । 'पदव्यवायेऽपि' (सू १०५७) इति निषेधं बाधितुमाङ्ग्रहणम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाकर्तुं शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ।

१९८। पदान्तस्य ।८।४।३७। पदान्तस्य नस्य णत्वं न स्यात् । रामान् ।

१९९। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।१।४।१३। यः प्रत्ययो यस्मा त्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । 'भवामि' 'भविष्या इत्यादौ विकरणविशिष्टस्याङ्गसंज्ञार्थं तदादिग्रहणम् । 'विधिः' इति किम् । स्त्री इयती । 'प्रत्यये' किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूत् ।

२००। अङ्गस्य ।६।४।१। इत्यधिकृत्य ।

२०१। टाङसिङसामिनात्स्याः ।७।१।१२। अकारान्तादङ्गाट्टादीनां क्रमा नादय आदेशाः स्युः । णत्वम् । रामेण ।

२०२। सुपि च ।७।३।१०२। यञादौ सुपि परेऽतोऽङ्गस्य दीर्घः स्या रामाभ्याम् ।

२०३। अतो भिस ऐस् ।७।१।९। अकारान्तादङ्गाद्भिस ऐस् स्यात् । अने ल्त्वात्सर्वादेशः । रामैः ।

२०४। ङेर्यः ।७।१।१३। अतोऽङ्गात्परस्य 'ङे' इत्यस्य यादेशः स्यात् । रामा इह स्थानिवद्भावेन यादेशस्य सुप्त्वात् 'सुपि च' (सू २०२) इति दीर्घः । 'संनिपात क्षणो विधिरनिमित्तं तद्विघातस्य' (प ८६) इति परिभाषा तु नेह प्रवर्तते । 'कष्टाय क्रम (सू २६७०) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ।

२०५। बहुवचने झल्येत् ।७।३।१०३। झलादौ बहुवचने सुपि परेऽतोऽङ्गस् कारः स्यात् । रामेभ्यः । 'बहुवचने' किम् । रामः । रामस्य । 'झलि' किम् । रामाणा 'सुपि' किम् । पचध्वम् । जश्त्वम् ।

२०६। वावसाने ।८।४।५६। अवसाने झलां चरो वा स्युः । रामात्–रामा द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे 'खरि च' (सू १ इति चर्त्वेऽप्यान्तरतम्यात्स एव । न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अत 'सः सि–' (सू २३४२) इति तादेश आरभ्यते ।

२०७। ओसि च ।७।३।१०४। ओसि परेऽतोऽङ्गस्यैकारः स्यात् । रामयोः ।

२०८। ह्रस्वनद्यापो नुट् ।७।१।५४। ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्य नुडागमः स्यात् ।

२०९। नामि ।६।४।३। नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । 'सुपि च' (सू २०२) इति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । 'ना (सू २०९) इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुप्येत्वे कृते ।

२१०। अपदान्तस्य मूर्धन्यः ।८।३।५५। आ पादपरिसमाप्तेरधिकारोऽयम् ।

२११। इण्कोः ।८।३।५७। इत्यधिकृत्य ।

२१२। आदेशप्रत्यययोः ।८।३।५९। 'सहेः साडः सः' (सू ३२५) इति सूत्र 'सः' इति षष्ठ्यन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । 'इण्कोः' किम् । रामस्य । 'आदेशप्रत्यययोः' किम् । सुपीः । सुपिसौ । सुपिसः । 'अपदान्तस्य' किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ।

२१३। सर्वादीनि सर्वनामानि। १। १। २७। सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः। 'तदन्तस्यापीयं संज्ञा'। 'द्वन्द्वे च' (सू २२४) इति ज्ञापकात्। तेन 'परमसर्वत्र' इति त्रल् 'परमभवकान्' इत्यत्राकच्च सिध्यति।

२१४। जसः शी। ७। १। १७। अदन्तात्सर्वनाम्नः परस्य जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। न च 'अर्वणस्तृ–' (सू ३६४) इत्यादाविव 'नानुबन्धकृतमनेकाल्त्वम्' (प ६) इति वाच्यम्। सर्वादेशात्प्रागित्संज्ञाया एवाभावात्। सर्वे।

२१५। सर्वनाम्नः स्मै। ७। १। १४। अतः सर्वनाम्नो 'ङे' इत्यस्य 'स्मै' स्यात्। सर्वस्मै।

२१६। ङसिङ्योः स्मात्स्मिनौ। ७। १। १५। अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः। सर्वस्मात्।

२१७। आमि सर्वनाम्नः सुट्। ७। १। ५२। अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात्। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयोऽप्यदन्ताः सर्वादयश्च पञ्चत्रिंशत्। सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। 'पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्'(ग सू १) 'स्वमज्ञातिधनाख्यायाम्' (ग सू २)। 'अन्तरं बहिर्योगोपसंव्यानयोः' (ग सू ३)। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् इति। उभशब्दो द्वित्वविशिष्टस्य वाचकः। अत एव नित्यं द्विवचनान्तः। तस्येह पाठस्तु 'उभकौ' इत्यकजर्थः। न च कप्रत्ययनेष्टसिद्धिः। द्विवचनपरत्वाभावेन 'उभयतः' 'उभयत्र' इत्यादाविवायच्प्रसङ्गात्। तदुक्तम्। 'उभयोऽन्यत्र' (वा २३२)। अन्यत्रेति द्विवचनपरत्वाभावे। 'उभयशब्दस्य द्विवचनं नास्ति' इति कैयटः। 'अस्ति' इति हरदत्तः। तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया 'प्रथमचरम–' (सू २२६) इति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति। उभये। डतरडतमौ प्रत्ययौ। 'प्रत्ययग्रहणे तदन्ता ग्राह्याः' (प २४)। यद्यपि 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' (प २८) 'सुप्तिङन्तम्–' (सू २९) इति ज्ञापकात्, तथापीह तदन्तग्रहणं केवलयोः संज्ञायाः प्रयोजनाभावात्। अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद्द्विबहुविषये निर्धारणे वर्तेते। तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा। 'त्व' 'त्व' इति द्वावप्यदन्तावन्यपर्यायौ। 'एक उदात्तोऽपरोऽनुदात्तः' इत्येके। 'एकस्तान्तः' इत्यपरे 'नेमः' इत्यर्धे। समः सर्वपर्यायः। तुल्यपर्यायस्तु नेह गृह्यते, 'यथासंख्यमनुदेशः समानाम्' (सू १२८) इति ज्ञापकात्। 'अन्तरं बहिर्योगोप–'(ग सू ३) इति गणसूत्रे 'अपुरि' इति वक्तव्यम्' (वा २४०)। अन्तरायां पुरि।

२१८। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। १। १। ३४। एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे–पूर्वाः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। 'व्यवस्थायाम्' किम्। दक्षिणा गाथकाः। कुशला इत्यर्थः। 'असंज्ञायाम्' किम्। उत्तराः कुरवः।

२१९ । स्वमज्ञातिधनाख्यायाम् । १ । १ । ३५ । ज्ञातिधनान्यवाचिनः स्वशब्दस्य या
प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे-स्वाः । आत्मीया इत्यर्थः । आत्मान इति वा । ज्ञातिध-
नवाचिनस्तु स्वाः, ज्ञातयोऽर्था वा ।

२२० । अन्तरं बहिर्योगोपसंव्यानयोः । १ । १ । ३६ । बाह्ये परिधानीये चार्थेऽन्त-
रशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे-अन्तरा वा गृहाः । बाह्या इत्यर्थः ।
अन्तरे-अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ।

२२१ । पूर्वादिभ्यो नवभ्यो वा । ७ । १ । १६ एभ्यो नवभ्यो ङसिङ्योः स्मात्स्मिनौ
वा स्तः । पूर्वस्मात्-पूर्वात् । पूर्वस्मिन्-पूर्वे । एवं परादीनामपि । शेषं सर्ववत् । एकशब्द:
संख्यायां नित्यैकवचनान्तः ।

२२२ । न बहुव्रीहौ । १ । १ । २९ । बहुव्रीहौ चिकीर्षिते सर्वनामसंज्ञा न स्यात् ।
त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासार्थ-
गेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथा लौकिकविग्रहवाक्य इव तत्राप्यकच्प्र-
वर्तेत । स च समासेऽपि श्रूयेत । 'अतिक्रान्तो भवकन्तमतिभवकान्' इति वत् । भाष्य-
कारस्तु 'त्वकत्पितृकः' 'मकत्पितृकः' इति रूपे इष्टापत्तिं कृत्वैतत्सूत्रं प्रत्याचख्यौ ।
यथोत्तरं मुनीनां प्रामाण्यम् । 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' (वा २२५) महासंज्ञा-
करणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति ।
सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मा अतिसर्वाय देहि ।
अतिकतरं कुलम् । आतितत् ।

२२३ । तृतीयासमासे । १ । १ । ३० । अत्र सर्वनामता न स्यात् । मासपूर्वाय ।
तृतीयासमासार्थवाक्येऽपि न । मासेन पूर्वाय ।

२२४ । द्वन्द्वे च । १ । १ । ३१ । द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदा-
यस्यायं निषेधः । न त्ववयवानाम् । न चैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्या-
सुडिति व्याख्यातत्वात् ।

२२५ । विभाषा जसि । १ । १ । ३२ । जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे
उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे-वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तम् । अ-
नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ।

२२६ । प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । १ । १ । ३३ । एते जसः कार्यं प्रत्यु-
क्तसंज्ञा वा स्युः । प्रथमे-प्रथमाः । शेषं रामवत् । तयः प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये-
द्वितयाः । शेषं रामवत् । नेमे-नेमाः । शेषं सर्ववत् । 'विभाषाप्रकरणे तीयस्य ङित्सूपसंख्या-
नम्' (वा २४२) । द्वितीयस्मै-द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्ग्रहणान्नेह । पटुजा-
तीयाय । निर्जरः ।

२२७ । जराया जरसन्यतरस्याम् । ७ । २ । १०१ । 'जरा'शब्दस्य 'जरस्' वा स्याद-
जादौ विभक्तौ । 'पदाङ्गाधिकारे तस्य च तदन्तस्य च' (प ३०) । अनेकाल्त्वात्सर्वादेशे प्राप्ते
'निर्दिश्यमानस्यादेशा भवन्ति' (प १३) । एकदेशविकृतस्यानन्यत्वात् 'जर'शब्दस्य 'जरस्' ।
निर्जरसौ । निर्जरसः । इनादीन्बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः ।

हलादौ च रामवत् । वृत्तिकृता तु 'पूर्वविप्रतिषेधेनेनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते 'निर्जरसिन' 'निर्जरसात्' इति रूपे । न तु 'निर्जरसा' 'निर्जरसः' इति केचित् इत्युक्तम् । तथा भिसि 'निर्जरसैः' इति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठ्येकवचने 'निर्जरस्य' इत्येव रूपमिति स्वीकृतम् । एतच्च भाष्यविरुद्धम् ।

२२८ । पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु । ६ । १ । ६३ । पाद दन्त नासिका मास हृदय निशा असृज् यूष दोष् यकृत् शकृत् उदक आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु 'आसनशब्दस्यासन्नादेशः' इति काशिकायामुक्तम् । तत्प्रामादिकम् । पादः । पादौ । पादाः । पादम् । पादौ । पदः—पादान् । पदा—पादेनेत्यादि ।

२२९ । सुडनपुंसकस्य । १ । १ । ४३ । सुडिति प्रत्याहारः । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ।

२३० । स्वादिष्वसर्वनामस्थाने । १ । ४ । १७ । कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदसंज्ञं स्यात् ।

२३१ । यचि भम् । १ । ४ । १८ । यकारादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् ।

२३२ । आ कडारादेका संज्ञा । १ । ४ । १ । इत ऊर्ध्वं 'कडाराः कर्मधारये' (सू ७५१) इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या परानवकाशा च । तेन शसादावचि भसंज्ञैव । न पदत्वम् । अतो जश्त्वं न । दतः । दता । जश्त्वम् । दद्भ्यामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि ।

२३३ । भस्य । ६ । ४ । १२९ । इत्यधिकृत्य ।

२३४ । अल्लोपोऽनः । ६ । ४ । १३४ । अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः स्यात् ।

२३५ । रषाभ्यां नो णः समानपदे । ८ । ४ । १ । एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । 'पूर्वस्मादपि विधौ स्थानिवद्भावः' इति पक्षे तु 'अड्व्यवाये' इत्येवात्र णत्वम् । 'पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । 'तस्य दोषः संयोगादिलोपलत्वणत्वेषु' (वा ४४०) इति निषेधात् ।

२३६ । नलोपः प्रातिपदिकान्तस्य । ८ । २ । ७ । नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्यासिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ।

२३७ । विभाषा ङिश्योः । ६ । ४ । १३६ । अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् ङिश्योः परयोः । यूष्णि —यूषणि । पक्षे रामवत् । 'पद्दन्न–' (सू २२८) इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथा च । औङः श्यामपि दोषन्नादेशो भाष्ये 'ककुद्दोषणी' इत्युदाहृतः । तेन 'पदङ्घ्रिश्चरणोऽस्त्रियाम्' 'स्वान्तं हृन्मानसं मनः' इति च संगच्छते । 'आसन्यं प्राणमूचुः' इति च । आस्ये भव आसन्यः । 'दोष्'-शब्दस्य नपुंसकत्वमत एव भाष्यात् । तेन 'दक्षिणं दोर्निशाचरः' इति संगच्छते ।

'भुजबाहू प्रवेष्टो दोः' इति साहचर्यात्पुंस्त्वमपि। 'दोषं तस्य तथाविधस्य भजतः' इति द्वयोरह्नोर्भवो द्व्यह्नः।

२३८। संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ। ६। ३। ११०। संख्यादिपूर्वस्याह्नस्याहन्नादेशो वा स्यान्ङौ। द्व्यह्नि-द्व्यहनि-द्व्यह्ने। विगतमहर्व्यह्नः। व्यह्नि-व्यहनि-व्यह्ने। अह्नः सायः सायाह्नः। सायाह्नि-सायाहनि-सायाह्ने।

इत्यदन्ताः।

विश्वपाः।

२३९। दीर्घाज्जसि च। ६। १। १०५। दीर्घाज्जसीचि च परे पूर्वसवर्णदीर्घो न स्यात्। वृद्धिः। विश्वपौ। सवर्णदीर्घः। विश्वपाः। यद्यपीह औङि 'नादिचि' (सू १६५) इत्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति। तथापि 'गौर्यौ' 'गौर्यः' इत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम्।

२४०। आतो धातोः। ६। ४। १४०। आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः स्यात्। 'अलोऽन्त्यस्य' (सू ४२)। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। 'धातोः' किम्। हाहान्। टा। सवर्णदीर्घः। हाहा। ङे। वृद्धिः। हाहै। ङसिङसोर्दीर्घः। हाहाः। हाहाः। ओसि वृद्धिः। हाहौः। ङौ। आद्गुणः। हाहे। शेषं विश्वपावत्। आतः' इति योगविभागादधातोरप्याकारलोपः क्वचित्। क्त्वः। भः।

इत्यादन्ताः।

हरिः। 'प्रथमयोः पूर्वसवर्णः' (सू १६४)। हरी।

२४१। जसि च। ७। ३। १०९। ह्रस्वान्तस्याङ्गस्य गुणः स्याज्जसि परे। हरयः।

२४२। ह्रस्वस्य गुणः। ७। ३। १०८। ह्रस्वस्य गुणः स्यात्संबुद्धौ। 'एङ्ह्रस्वात्' (सू १९३) इति संबुद्धिलोपः। हे हरे। हरिम्। हरी। हरीन्।

२४३। शेषो घ्यसखि। १। ४। ७। अनदीसंज्ञौ ह्रस्वौ याविवर्णोवर्णौ तदन्तं सखिवर्जं घिसंज्ञं स्यात्। 'शेषः' किम्। मत्यै। एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थम्। 'ह्रस्वौ' किम्। वातप्रम्ये। 'यू' किम्। मात्रे।

२४४। आङो नाऽस्त्रियाम्। ७। ३। १२०। घेः परस्याङो ना स्यादस्त्रियाम् आङिति टासंज्ञा प्राचाम्। हरिणा। 'अस्त्रियाम्' किम्। मत्या।

२४५। घेर्ङिति। ७। ३। १११। घिसंज्ञकस्य ङिति सुपि गुणः स्यात्। हरये। 'घेः' किम्। सख्ये। 'ङिति' किम्। हरिभ्याम्। 'सुपि' किम्। पट्वी। 'घेर्ङिति' (सू २४५) इति गुणे जाते।

२४६। ङसिङसोश्च। ६। १। ११०। एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात्। हरेः। हरेः। हर्योः। हरीणाम्।

२४७। अच्च घेः। ७। ३। ११९। इदुद्भ्यामुत्तरस्य ङेरौत्स्याद्घेरन्तादेशश्चाकारः। हरौ। हर्योः। हरिषु। एवं श्रीपत्यग्निरविकव्यादयः।

२४८। अनङ् सौ। ७। १। ९३। सख्युरङ्गस्यानङादेशः स्यादसंबुद्धौ सौ परे ङिच्च' (सू ४३) इत्यन्तादेशः।

२४९। अलोऽन्त्यात्पूर्व उपधा। १।१।६५। अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात्।

२५०। सर्वनामस्थाने चासंबुद्धौ। ६।४।८। नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे।

२५१। अपृक्त एकाल्प्रत्ययः। १।२।४१। एकाल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्।

२५२। हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्। ६।१।६८। हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सु ति सीत्येतदपृक्तं हल् लुप्यते। 'हल्ङ्याब्भ्यः' किम्। ग्रामणीः। 'दीर्घात्' किम्। निष्कौशाम्बिः। अतिखट्वः। 'सु ति सि' इति किम्। अभैत्सीत्। तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति। 'अपृक्तम्' इति किम्। बिभर्ति। 'हल्' किम्। बिभेद। 'प्रथमहल्' किम्। राजा। नलोपो न स्यात्संयोगान्तलोपस्यासिद्धत्वात्। सखा। हे सखे।

२५३। सख्युरसंबुद्धौ। ७।१।९२। सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णित्कार्यकृत्स्यात्।

२५४। अचो ञ्णिति। ७।२।११५। ञिति णिति च परेऽजन्ताङ्गस्य वृद्धिः स्यात्। सखायौ। सखायः। सखायम्। सखायौ। घिसंज्ञाभावान्न तत्कार्यम्। सख्या। सख्ये।

२५५। ख्यत्यात्परस्य। ६।१।११२। खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात्। सख्युः।

२५६। औत्। ७।३।११८। इदुद्भ्यां परस्य ङेरौत्स्यात्। उकारानुवृत्तिरुत्तरार्था। सख्यौ। शेषं हरिवत्। शोभनः सखा सुसखा। सुसखायौ। सुसखायः। अनङ्णिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः। समुदायस्य सखिरूपत्वाभावात् 'असखि' (सू २४३) इति निषेधाप्रवृत्तेर्घिसंज्ञा। सुसखिना। सुसखये। ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् 'ख्यत्यात्–' (सू २५५) इत्युत्वं न। सुसखेः। सुसखावित्यादि। एवमतिशयितः सखातिसखा। 'परमः सखा यस्य' इति विग्रहे परमसखा। परमसखायावित्यादि। गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते। सखीमतिक्रान्तोऽतिसखिः। लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच्। हरिवत्। इहानङ्णित्त्वे न भवतः। 'गोस्त्रियोः–' (सू ६५६) इति ह्रस्वेन सखिशब्दस्य लाक्षणिकत्वात्। 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात्' (प ११४)।

२५७। पतिः समास एव। १।४।८। पतिशब्दः समास एव घिसंज्ञः स्यात्। पत्या। पत्ये। पत्युः। पत्युः। पत्यौ। शेषं हरिवत्। समासे तु भूपतिना। भूपतये। कतिशब्दो नित्यं बहुवचनान्तः।

२५८। बहुगणवतुडति संख्या। १।१।२३। एते संख्यासंज्ञाः स्युः।

२५९। डति च। १।१।२५। डत्यन्ता संख्या षट्संज्ञा स्यात्।

२६० प्रत्ययस्य लुक्श्लुलुपः। १।१।६१। लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्।

२६१। षड्भ्यो लुक्। ७।१।२२। षड्भ्यः परयोर्जश्शसोर्लुक् स्यात्।

२६२। प्रत्ययलोपे प्रत्ययलक्षणम्। १। १। ६२। प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात्। इति 'जसि च' (सू २४१) इति गुणे प्राप्ते।

२६३। न लुमताऽङ्गस्य। १। १। ६३। लुक् श्लु लुप् एते लुमन्तः। लुमताशब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति। कति। कतिभिः। कतिभ्यः। कतिभ्यः। कतीनाम्। कतिषु। अस्मद्युष्मद्षट्संज्ञकास्त्रिषु सरूपाः। त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः। त्रिभ्यः।

२६४। त्रेस्त्रयः। ७। १। ५३। त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। परमत्रयाणाम्। गौणत्वे तु नेति केचित्। प्रियत्रीणाम्। वस्तुतस्तु प्रियत्रयाणाम्। त्रिषु। द्विशब्दो नित्यं द्विवचनान्तः।

२६५। त्यदादीनामः। ७। २। १०२। एषामकारोऽन्तादेशः स्याद्विभक्तौ। 'द्विपर्यन्तानामेवेष्टिः' (वा ४४६८)। द्वौ। द्वौ। द्वाभ्याम्। द्वाभ्याम्। द्वाभ्याम्। द्वयोः। द्वयोः। 'द्विपर्यन्तानाम्' इति किम्। भवान्। भवन्तौ। भवन्तः। संज्ञायामुपसर्जनत्वे च नात्वम्। सर्वाद्यन्तर्गणकार्यत्वात्। द्विर्नाम कश्चित्। द्विः। द्वी। द्वयः। द्वावतिक्रान्तोऽतिद्विः। हरिवत्। प्राधान्ये तु परमद्वावित्यादि। औडुलोमिः। औडुलोमी। उडुलोमाः। 'लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः' (वा २५६०)। बाह्वादीञोऽपवादः। औडुलोमिम्। औडुलोमी। उडुलोमान्।

इतीदन्ताः।

'वातप्रमीः' (उ ४४१) इत्युणादिसूत्रेण माङ ईप्रत्ययः। स च कित्। वातं प्रमिमीते वातप्रमीः। 'दीर्घाज्जसि च' (सू२२९)। वातप्रम्यौ। वातप्रम्यः। हे वातप्रमीः। 'अमि पूर्वः' (सू१९४)। वातप्रमीम्। वातप्रम्यौ। वातप्रमीन्। वातप्रम्या। वातप्रमीभ्याम्। वातप्रम्ये। वातप्रमीभ्याम्। वातप्रम्यः। वातप्रमीभ्याम्। वातप्रम्यः। वातप्रम्योः। वातप्रम्याम्। दीर्घत्वान्न नुट्। ङौ तु सवर्णदीर्घः। वातप्रमी। वातप्रम्योः। वातप्रमीषु। एवं ययीपप्यादयः। यान्त्यनेनेति ययीर्मार्गः। पाति लोकमिति पपीः सूर्यः। 'यापोः किद्द्वे च' (उ४३९) इति ईप्रत्ययः। क्विबन्तवातप्रमीशब्दस्य त्वामि शसि ङौ च विशेषः। वातप्रम्यम्। वातप्रम्यः। वातप्रम्यि। 'एरनेकाचः—' (सू२७२) इति वक्ष्यमाणो यण्। प्रधीवत्। बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी। दीर्घङ्यन्तत्वात् 'हल्ङ्याप् (सू २५२) इति सुलोपः।

२६६। यू स्त्र्याख्यौ नदी। १। ४। ३। ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। 'प्रथमलिङ्गग्रहणं च' (वा १०३६)। पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः।

२६७। अम्बार्थनद्योर्ह्रस्वः। ७। ३। १०७। अम्बार्थानां नद्यन्तानां च ह्रस्वः स्यात्संबुद्धौ। हे बहुश्रेयसि। शसि बहुश्रेयसीन्।

२६८। आण्नद्याः। ७। ३। ११२। नद्यन्तात्परेषां ङितामाडागमः स्यात्।

२६९। आटश्च। ६। १। ९०। आटोऽचि परे वृद्धिरेकादेशः स्यात्। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयस्याः। नद्यन्तात्परत्वान्नुट्। बहुश्रेयसीनाम्।

२७०। ङेराम्नद्याम्नीभ्यः। ७। ३। ११६। नद्यन्तादाबन्तान्नीशब्दाच्च ङेराम् स्यात्। इह परत्वादाटा नुड् बाध्यते। बहुश्रेयस्याम्। शेषमीप्रत्ययान्तवातप्रमीवत्। अङ्यन्त-

त्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन्कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । 'हल्ङ्याप्–' (सू २५२) इति सुलोपः ।

२७१ । अचि श्नुधातुभ्रुवां य्वोरियङुवङौ । ६ । ४ । ७७ । श्नुप्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोः 'भ्रू' इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे । 'ङिच्च' (सू ४३) इत्यन्तादेशः । आन्तरतम्यादेरियङ् । ओरुवङ् । इतीयङि प्राप्ते ।

२७२ । एरनेकाचोऽसंयोगपूर्वस्य । ६ । ४ । ८२ । धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ प्रत्यये परे । इति यण् । कुमार्यौ । कुमार्यः । हे कुमारि । अमि शसि च कुमार्यम् । कुमार्यः । कुमार्यै । कुमार्याः । कुमार्याः । कुमारीणाम् । कुगार्याम् । कुमार्योः । प्रधीः । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव यण् । उन्न्यौ । उन्न्यः । हे उन्नीः । उन्न्यम् । ङेराम् । उन्न्याम् । एवं ग्रामणीः । 'अनेकाचः' किम् । नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । नियः । ङेराम् । नियाम् । 'असंयोगपूर्वस्य' किम् । सुश्रियौ । यवक्रियौ । 'गतिकारकेतरपूर्वपदस्य यण् नेष्यते' (वा ५०३४) । शुद्धधियौ । परमधियौ । कथं तर्हि 'दुर्धियः' 'वृश्चिकाभियः' इत्यादि । उच्यते । 'दुःस्थिता धीर्येषाम्' इति विग्रहे 'दुर्' इत्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसंबन्धिनी भीर्वृश्चिकभीरित्युत्तरपदलोपो वा ।

२७३ । न भूसुधियोः । ६ । ४ । ८५ । एतयोर्यण् न स्यादचि सुपि । सुधियौ । सुधिय इत्यादि । सखायमिच्छति सखीयति । ततः क्विप् । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते 'क्वौ लुप्तं न स्थानिवत्' (वा ४३१) । एकदेशविकृतस्यानन्यतयानङ्णित्त्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते । ततोऽपि परत्वात् 'सख्युरसंबुद्धौ' (सू २५३) इति प्रवर्तते । सखायम् । सखायौ । शसि यण् । सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छतीति सुतीः । सख्यौ । सुख्यौ । सुत्यौ । 'ख्यत्यात्–' (सू २९९) इति दीर्घस्यापि ग्रहणादुकारः । सख्युः । सुख्युः । सुत्युः । लूनमिच्छतीति लूनीः । क्षाममिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां ङसिङसोर्यण् । नत्वमत्वयोरसिद्धत्वात् 'ख्यत्यात्–' (सू २९९) इत्युत्वम् । लून्युः । क्षाम्युः । प्रस्तीम्युः । शुष्कीयतेः क्विप् । शुष्कीः । पक्कीः । इयङ् । शुष्कियौ । शुष्कियः । ङसिङसोः शुष्किय इत्यादि ।

इतीदन्ताः ।

शंभुर्हरिवत् । एवं विष्णुवायुभान्वादयः ।

२७४ । तृज्वत्क्रोष्टुः । ७ । १ । ९५ । क्रोष्टुस्तृजन्तेन तुल्यं वर्ततेऽसंबुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः ।

२७५ । ऋतो ङिसर्वनामस्थानयोः । ७ । ३ । ११० । ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ।

---

१ इदं च 'गतिकारकपूर्वस्यैवेष्यते' इति भाष्यफलितार्थकथनम् ।

२७६। ऋदुशनस्पुरुदंसोऽनेहसां च।७।१।९४। ऋदन्तानामुशनसादीनां चानङ् स्यादसंबुद्धौ सौ परे।

२७७। अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्।६।४।११। अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे। नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव। तेन पितृभ्रातृप्रभृतीनां न। उद्गातृशब्दस्य तु भवत्येव। 'समर्थ-'(सू ६४७)सूत्रे 'उद्गातारः' इति भाष्यप्रयोगात्। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टारम्। क्रोष्टारौ। क्रोष्टून्।

२७८। विभाषा तृतीयादिष्वचि।७।१।९७। अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे।

२७९। ऋत उत्।६।१।१११। ऋदन्ताङ्ङसिङसोरति परे उकार एकादेशः स्यात्। रपरत्वम्।

२८०। रात्सस्य।८।२।२४। रेफात्संयोगान्तस्य सस्यैव लोपः। नान्यस्य। रेफस्य विसर्गः। क्रोष्टुः। आमि परत्वात्तृज्वद्भावे प्राप्ते। 'नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन' (वा ४३७४)। क्रोष्टूनाम्। क्रोष्टरि। क्रोष्ट्रोः। पक्षे हलादौ च शंभुवत्।

इत्युदन्ताः।

हूहूः। हूह्वौ। हूह्वः। हूहूम्। हूह्वौ। हूहूनित्यादि। अतिचमूशब्दे तु नदीकार्यं विशेषः। हे अतिचमु। अतिचम्वे। अतिचम्वाः। अतिचम्वाः। अतिचमूनाम्। अतिचम्वाम्। खलपूः।

२८१। ओः सुपि।६।४।८३। धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादजादौ सुपि। 'गतिकारकेतरपूर्वपदस्य यण् नेष्यते' (वा ५०३४)। खलप्वौ। खलप्व इत्यादि। एवं सुल्वादयः। 'अनेकाचः' किम्। लूः। लुवौ। लुवः। 'धात्ववयव-' इति किम्। उल्लूः। उल्ल्वौ। उल्ल्वः। 'असंयोगपूर्वस्य' किम्। कटप्रूः। कटप्रुवौ। कटप्रुवः। 'गति-' इत्यादि किम्। परमलुवौ। 'सुपि' किम्। लुलुवतुः। स्वभूः। 'न भूसुधियोः' (सू २७२)। स्वभुवौ। स्वभुवः। एवं स्वयंभूः।

२८२। वर्षाभ्वश्च।६।४।८४। अस्योवर्णस्य यण् स्यादचि सुपि। वर्षाभ्वौ। वर्षाभ्वः। दृम्भतीति दृम्भूः। 'अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः' (उ ९३) इत्युणादिसूत्रेण व्युत्पादितः। दृम्भ्वौ। दृम्भ्वः। दृम्भूम्। दृम्भ्वौ। दृम्भून्। शेषं हूहूवत्। 'दृन्' इति नान्ते हिंसार्थेऽव्यये भुवः क्विप्। दृन्भूः। 'दृन्करपुनःपूर्वस्य भुवो यण् वक्तव्यः' (वा ४११८)। दृन्भ्वौ। दृन्भ्व इत्यादि। खलपूवत्। करभूः। करभ्वौ। करभ्वः। दीर्घपाठे तु 'करः' एव 'कारः'। स्वार्थिकः प्रज्ञाद्यण्। कारभ्वौ। कारभ्वः। पुनर्भूर्यौगिकः पुंसि। पुनर्भ्वावित्यादि। 'दृन्भू'-'काराभू'-शब्दौ स्वयंभूवत्।

धाता। हे धातः। धातारौ। धातारः। 'ऋवर्णान्नस्य णत्वं वाच्यम्' (वा ४९६९)। धातॄणामित्यादि। एवं नप्त्रादयः। उद्गातारौ। पिता। व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्न दीर्घः। पितरौ। पितरः। पितरम्। पितरौ। शेषं धातृवत्। एवं जामातृभ्रात्रादयः। ना। नरौ। नरः। हे नः।

इत्यृदन्ताः।

२८३ । नृ च । ६ । ४ । ६ । 'नृ' इत्येतस्य नामि वा दीर्घः स्यात् । नृणाम्–नृणाम् ।

इत्यृदन्ता ।

'कॄ' 'तॄ' अनयोरनुकरणे 'प्रकृतिवदनुकरणं–'(प ३७) इति वैकल्पिकातिदेशादित्वे रपरत्वम् । कीः । किरौ । किरः । तीः । तिरौ । तिर इत्यादि । गीर्वत् । इत्त्वाभावपक्षे तु 'ऋदुशनस्–' (सू २७६) इति 'ऋतो ङि–' (सू २७९) इति च तपरकरणादनङ्गुणौ न । कॄः । क्रौ । क्रः । कॄम् । क्रौ । कॄन् । क्रा । क्रे इत्यादि ।

इत्यॄदन्ताः ।

'गम्ऌ' 'शक्ऌ' अनयोरनुकरणेऽनङ् । गमा । शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गमॄन् । गम्ला । गम्ले । ङसिङसोस्तु 'ऋत उत्' (सू २७९) इत्युत्त्वे लपरत्वे 'संयोगान्तस्य लोपः' (सू ५४) । गमुल् । शकुल् इत्यादि ।

इति ऌदन्ताः ।

सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः ।

इत्येदन्ताः ।

२८४ । गोतो णित् । ७ । १ । ९० । गोशब्दात्परं सर्वनामस्थानं णिद्वत्स्यात् । गौः । गावौ । गावः ।

२८५ । औतोऽम्शसोः । ६ । १ । ९३ । 'आ ओतः' इति छेदः । ओकारादम्शसोरचि परे आकार एकादेशः स्यात् । शसा साहचर्यात्सुबेवाम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् । गावौ । गाः । गवा । गवे । गोरित्यादि । '[1]ओतो णिदिति वाच्यम्' (वा ५०३९) । विहितविशेषणं च । तेन । सुद्यौः । सुद्यावौ । सुद्यावः । 'ओकारान्ताद्विहितं सर्वनामस्थानम्' इति व्याख्यानान्नेह । हे भानो । भानवः । ङः शंभुः स्मृतो येन सः स्मृतोः । स्मृतावौ । स्मृतावः । स्मृताम् । स्मृतावौ । स्मृता इत्यादि ।

इत्योदन्ताः ।

२८६ । रायो हलि । ७ । २ । ८५ । रैशब्दस्याकारोऽन्तादेशः स्याद्धलि विभक्तौ । राः । अच्यायादेशः । रायौ । रायः । रायम् । रायौ । रायः । राया । राभ्यामित्यादि ।

इत्यैदन्ताः ।

ग्लौः । ग्लावौ । ग्लावः । ग्लावम् । ग्लावौ । ग्लाव इत्यादि । 'औतोऽम्शसोः' (सू २८५) इतीह न प्रवर्तते । 'ऐऔच्' (प्र सू ४) इति सूत्रेणैदौतोः सावर्ण्याभावज्ञापनात् ।

इत्यौदन्ताः ।

इत्यजन्तपुंलिङ्गप्रकरणम् ।

---

१ इदं च (३६१९) वार्तिकव्याख्यायाम् 'ओतो णित्' इति सूत्रं पठितव्यम् इति कैयटेन सूत्रप्रतिनिधित्वेनोक्तम् 'अनवकाशमात्वं वृद्धिं बाधिष्यते' इति भाष्यध्वनितम् ।

अथाजन्तस्त्रीलिङ्गप्रकरणम् ।

रमा ।

२८७ । औङ आपः । ७ । १ । १८ । आबन्तादङ्गात्परस्यौङः शी स्यात् । 'औङ्' इत्यौकारविभक्तेः संज्ञा । रमे । रमाः ।

२८८ । संबुद्धौ च । ७ । ३ । १०६ । आप एकारः स्यात्संबुद्धौ । 'एङ्ह्रस्वात्–' (सू १९३) इति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः । स्त्रीत्वान्नत्वाभावः ।

२८९ । आङि चापः । ७ । ३ । १०५ । आङि ओसि च परे आबन्तस्याङ्गस्यैकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ।

२९० । याडापः । ७ । ३ । ११३ । आपः परस्य ङिद्वचनस्य याडागमः स्यात् । 'वृद्धिरेचि' (सू ७२) । रमायै । सवर्णदीर्घः । रमायाः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ।

२९१ । सर्वनाम्नः स्याड्ढ्रस्वश्च । ७ । ३ । ११४ । आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः । सर्वस्यै । सर्वस्याः । सर्वस्याः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् 'आमि सर्वनाम्नः–' (सू २१७) इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादयोऽप्याबन्ताः ।

२९२ । विभाषा दिक्समासे बहुव्रीहौ । १ । १ । २८ । अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै–उत्तरपूर्वायै । 'दिङ्नामान्यन्तराले' (सू ८४५) इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । 'अपुरि' इत्युक्तेर्नेह । अन्तरायै नगर्यै ।

२९३ । विभाषा द्वितीयातृतीयाभ्याम् । ७ । ३ । ११५ । आभ्यां ङितः स्याट् स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसंख्यानात् । द्वितीयस्यै–द्वितीयायै । द्वितीयस्याः–द्वितीयायाः । द्वितीयस्याः–द्वितीयायाः । द्वितीयस्याम्–द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । 'अम्बार्थनद्योर्ह्रस्वः' (सू २६७) । हे अम्ब । हे अक्क । हे अल्ल । 'असंयुक्ता[1] ये डलकास्तद्वतां ह्रस्वो न' (वा ४५९२) । हे अम्बाडे । हे अम्बाले । हे अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य 'जरसी' इति केचिदाहुः । तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य 'औङ आपः' (सू २८७), 'आङि चापः' (सू २८९), 'याडापः' (सू २९०), 'ह्रस्वनद्यापः–' (सू २०८), 'ङेराम्–' (सू २७०) इति च पञ्चापि विधयः प्राप्ताः । एवं नसुनिशूपृत्सु । तथाप्यनल्विधावित्युक्तेर्न भवन्ति । 'आ आप्' इति प्रश्लिष्याकाररूपस्यैवापः सर्वत्र ग्रहणात् । एवं 'हल्ङ्याप्–'(सू २५२)सूत्रेऽपि 'आ आप्' 'ङी ई' इति प्रश्लेषात् 'अतिखट्वः,' 'निष्कौशाम्बिः' इत्यादिसिद्धेर्दीर्घग्रहणं प्रत्याख्येयम् । न चैवमपि 'अतिखट्वाय' इत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य

---

१ असंयुक्ता इति तु 'अम्बाले, अम्बाले, अम्बिके, इति भाष्योदाहरणाल्लभ्यते ।

याद्विधानात् । 'उपसर्जनस्त्रीप्रत्यये तदादिनियमात्' । 'पद्दन्–' (सू २२८) इति नासिकाया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ।

२९४ । व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । ८ । २ । ३६ । व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निड्भिः । सुपि 'डः सि धुट्' (सू १३१) इति पक्षे धुट् । चर्त्वम् । तस्यासिद्धत्वात् 'चयो द्वितीया–'(वा ५०२३) इति टतयोष्ठथौ न । 'न पदान्ताट्टोः–' (सू ११४) इति ष्टुत्वं न । निट्त्सु । निट्सु ।

२९५ । षढोः कः सि । ८ । २ । ४१ । षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्चादिसूत्रे 'दादेर्धातोः–' (सू ३२५) इति सूत्रात् 'धातोः' इत्यनुवर्तयन्ति । तन्मते जश्त्वेन जकारे । निज्भ्याम् । निज्भिः । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । निच्छु । 'चोः कुः' (सू ३७८) इति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् । 'मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ (वा ३४९६) । पृतः । पृता । पृद्भ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न । मत्या ।

२९६ । ङिति ह्रस्वश्च । १ । ४ । ६ । इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ चेवर्णोवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । 'आण्नद्याः' (सू २६८) । मत्यै–मतये । मत्याः–मतेः । मत्याः–मतेः । नदीत्वपक्षे 'औत्' (सू २५६) इति ङेरौत्त्वे प्राप्ते ।

२९७ । इदुद्भ्याम् । ७ । ३ । ११७ । नदीसंज्ञकाभ्यामिदुद्भ्यां परस्य ङेराम् स्यात् । पक्षे 'अच्च घेः' (सू २४७) मत्याम्–मतौ । एवं श्रुतिस्मृत्यादयः ।

२९८ । त्रिचतुरोः स्त्रियां तिसृचतसृ । ७ । २ । ९९ । स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः ।

२९९ । अचि र ऋतः । ७ । २ । १०० । तिसृ चतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्त्वानामपवादः । तिस्रः । तिस्रः । तिसृभिः । तिसृभ्यः । तिसृभ्यः । आमि 'नुमचिर–' (वा ४३७४) इति नुट् ।

३०० । न तिसृचतसृ । ६ । ४ । ४ । एतयोर्नामि दीर्घो न स्यात् । तिसृणाम् । तिसृषु । 'स्त्रियाम्' इति त्रिचतुरोर्विशेषणान्नेह । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः । मतिवत् । आमि तु 'प्रियत्रयाणाम्' इति विशेषः । 'प्रियास्तिस्रो यस्य सः' इति विग्रहे तु प्रियतिसा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । स्वमोर्लुका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेशः । 'न लुमता–' (सू २६३) इति निषेधस्यानित्यवात्पक्षे प्रियतिसृ । 'रादेशात्पूर्वविप्रतिषेधेन नुम्' (वा ५०३६) । प्रियतिसृणी । प्रियतिसृणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पात्पर्यायेण नुम्रभावौ । प्रियतिस्रा । प्रियतिसृणेत्यादि । द्वेरत्वे सत्याप् । द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः ।

---

१ इह 'प्रियतिसृणी प्रियतिसृणि' इति 'प्रत्ययोत्तरपदयोश्च' (सू १३७३) इति सूत्रभाष्योदाहरणं मानम् ।

गौरी । गौर्यौ । गौर्यः । नदीकार्यम् । हे गौरि । गौर्यै इत्यादि । एवं वाणीनद्यादयः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादनङि णिदद्भावे च प्राप्ते । 'विभक्तौ लिङ्गविशिष्टाग्रहणम्' (वा ४२३८) । सखी । सख्यौ । सख्य इत्यादि गौरीवत् । अङ्यन्तत्वान्न सुलोपः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतन्त्र्यादयः । स्त्री । हे स्त्रि ।

३०१ । स्त्रियाः । ६ । ४ । ७९ । 'स्त्री'शब्दस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ।

३०२ । वाम्शसोः । ६ । ४ । ८० । अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम्–स्त्रीम् । स्त्रियौ । स्त्रियः–स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । स्त्रियाः । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु । स्त्रियमतिक्रान्तोऽतिस्त्रिः । अतिस्त्रियौ ।

गुणनाभावोत्वनुड्भिः परत्वात्पुंसि बाध्यते ।
क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥

जसि च' (सू २४९) । अतिस्त्रयः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रयः । "वाम्शसोः' (सू ३०२) । अतिस्त्रियम्–अतिस्त्रिम् । अतिस्त्रियौ । अतिस्त्रियः–अतिस्त्रीन् । अतिस्त्रिणा । 'घेर्ङिति' (सू २४५) । अतिस्त्रये । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रियोः । अतिस्त्रीणाम् । 'अच्च घेः' (सू २४७) । अतिस्त्रौ । अतिस्त्रियोः ।

ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया ।
इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥

क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । ङिप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रये–अतिस्त्रिणे । अतिस्त्रेः–अतिस्त्रिणः । अतिस्त्रेः–अतिस्त्रिणः । अतिस्त्रियोः–अतिस्त्रिणोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । 'ङिति ह्रस्वश्च' (सू २९६) इति ह्रस्वान्तत्वप्रयुक्तो विकल्पः । 'अस्त्री' इति तु इयङुवङ्स्थानावित्यस्यैव पर्युदासः, तत्संबद्धस्यैवानुवृत्तेः । दीर्घस्यायं निषेधः । न तु ह्रस्वस्य । अतिस्त्रियै–अतिस्त्रये । अतिस्त्रियाः–अतिस्त्रेः । अतिस्त्रियाः–अतिस्त्रेः । अतिस्त्रीणाम् । अतिस्त्रियाम्–अतिस्त्रौ । श्रीः । श्रियौ । श्रियः ।

३०३ । नेयङुवङ्स्थानावस्त्री । १ । ४ । ४ । इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तः, न तु स्त्री । हे श्रीः । श्रियौ । श्रियै–श्रिये । श्रियाः–श्रियः ।

३०४ । वामि । १ । ४ । ५ । इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तः, न तु स्त्री । श्रीणाम्–श्रियाम् । श्रियाम्–श्रियि । 'प्रधी'शब्दस्य तु वृत्तिकारादीनां मते, लक्ष्मीवद्रूपम् । 'पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । 'लिङ्गान्तरानभिधायकत्वं तत्' इति कैयटमते तु पुंवद्रूपम् । 'प्रकृष्टा धीः' इति विग्रहे तु 'लक्ष्मी'वत् । अमि शसि च 'प्रध्यम्' 'प्रध्यः' इति विशेषः । 'सुष्ठु धीर्यस्याः' 'सुष्ठु ध्यायति' वेति विग्रहे तु वृत्तिकारमते 'सुधीः' 'श्री'वत् । मतान्तरे पुंवत् । 'सुष्ठु धीः' इति विग्रहे तु 'श्री'वदेव । 'ग्रामणीः' पुंवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विनापि स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । 'धेनुः' 'मति'वत् ।

३०५ । स्त्रियां च । ७ । १ । ९६ । स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ।

३०६। ऋन्नेभ्यो ङीप्। ४। १। ५। ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् स्यात्। क्रोष्ट्री। क्रोष्ट्र्यौ। क्रोष्ट्र्यः। 'वधूः' 'गौरी'वत्। 'भ्रूः' 'श्री'वत्। हे सुभ्रूः। कथं तर्हि 'हा पितः क्वासि हे सुभ्रु' इति भट्टिः। प्रमाद एवायमिति बहवः। 'खलपूः' पुंवत्। पुनर्भूः। 'दृन्कर–' (वा ४११८) इति यणा उवङो बाधनात् 'नेयङुवङ्–' (सू ३०३) इति निषेधो न। हे पुनर्भु। पुनर्भ्वम्। पुनर्भ्वौ। पुनर्भ्वः।

३०७। एकाजुत्तरपदे णः। ८। ४। १२। एकाजुत्तरपदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यात्। आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम्। यणं बाधित्वा परत्वान्नुट्। पुनर्भूणाम्। वर्षाभूः। भेकजातौ नित्यस्त्रीत्वाभावात् हे वर्षाभूः। कैयटमते। मतान्तरे तु हे वर्षाभु। 'भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमान्' इति यादवः। 'वर्षाभ्वश्च' (सू २८२)। वर्षाभ्वौ। वर्षाभ्वः। 'स्वयंभूः' पुंवत्।

३०८। न षट्स्वस्रादिभ्यः। ४। १। १०। षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः।

स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।
याता मातेति सप्तैते स्वस्रादय उदाहृताः॥

'अप्तृन्–'(सू २७७) इति दीर्घः। स्वसा। स्वसारौ। स्वसारः। माता पितृवत्। शसि मातॄः। 'द्यौः' 'गो'वत्। 'राः' पुंवत्। 'नौः' 'ग्लौ'वत्।

इत्यजन्तस्त्रीलिङ्गप्रकरणम्।

अथाजन्तनपुंसकलिङ्गप्रकरणम्।

३०९। अतोऽम्। ७। १। २४। अतोऽङ्गात्क्लीबात्स्वमोरम्स्यात्। 'अमि पूर्वः' (सू १९४)। ज्ञानम्। 'एङ्ह्रस्वात्–' (सू १९३) इति हल्मात्रलोपः। हे ज्ञान।

३१०। नपुंसकाच्च। ७। १। १९। क्लीबात्परस्यौङः शी स्यात्। भसंज्ञायाम्।

३११। यस्येति च। ६। ४। १४८। भस्येवर्णावर्णयोर्लोपः स्यादीकारे तद्धिते च परे। इत्यकारलोपे प्राप्ते। 'औङः श्यां प्रतिषेधो वाच्यः' (वा ४१८९)। ज्ञाने।

३१२। जश्शसोः शिः। ७। १। २०। क्लीबादनयोः शिः स्यात्।

३१३। शि सर्वनामस्थानम्। १। १। ४२। 'शि' इत्येतदुक्तसंज्ञं स्यात्।

३१४। नपुंसकस्य झलचः। ७। १। ७२। झलन्तस्याजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं रामवत्। एवं धनवनफलादयः।

३१५। अद्ड्डतरादिभ्यः पञ्चभ्यः। ७। १। २५। एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात्।

३१६। टेः। ६। ४। १४३। डिति परे भस्य टेर्लोपः स्यात्। 'वावसाने' (सू २०६)। कतरत्–कतरद्। कतरे। कतराणि। 'भस्य' इति किम्। पञ्चमः। टेर्लुप्तत्वात् 'प्रथमयोः–' (सू १६४) इति पूर्वसवर्णदीर्घः 'एङ्ह्रस्वात्–' (सू १९३) इति संबुद्धिलोपश्च न भवति।

हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् । कतमत् । इतरत् । अन्यत् । अन्यतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव । 'एकतरात्प्रतिषेधो वक्तव्यः' (वा ४२८७) । एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी-अजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् ।

३१७ । सान्तमहतः संयोगस्य । ६ । ४ । १० । सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि-अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाज्जरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम्-अजरम् । अजरसी-अजरे । अजरांसि-अजराणि । शेषं पुंवत् । 'पद्दन्-' (सू २२८) इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्ना । उदभ्यामित्यादि । आसानि । आस्ना । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये 'मांसपचन्या उखायाः' इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । 'पद्दन्-' (सू २२८) इत्यत्र हि 'छन्दसि' इत्यनुवर्तितं वृत्तौ । तथापि 'अपो भि' (सू ४४२) इत्यत्र 'मासश्छन्दसि' (वा ४६३४) इति वार्तिके 'छन्दोग्रहणसामर्थ्याल्लोकेऽपि क्वचित्' इति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् ।

३१८ । ह्रस्वो नपुंसके प्रातिपदिकस्य । १ । २ । ४७ । क्लीबे प्रातिपदिकस्याजन्तस्य ह्रस्वः स्यात् । 'श्रीपं' 'ज्ञान'वत् । श्रीपाय । अत्र संनिपातपरिभाषया 'आतो धातोः' (सू २४०) इत्याकारलोपो न ।

३१९ । स्वमोर्नपुंसकात् । ७ । १ । २३ । क्लीबादङ्गात्परयोः स्वमोर्लुक् स्यात् । वारि ।

३२० । इकोऽचि विभक्तौ । ७ । १ । ७३ । इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । 'न लुमता-' (सू २६३) इति निषेधस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे-हे वारि । 'आङो ना-' (सू २४४) । वारिणा । 'घेर्ङिति' (सू २४५) इति गुणे प्राप्ते । 'वृद्ध्यौत्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन' (वा ४३७३) । वारिणे । वारिणः । वारिणोः । 'नुमचिर-' (वा ४३७४) इति नुट् । 'नामि' (सू २०९) इति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ।

३२१ । तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य । ७ । १ । ७४ । प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये-अनादिने इत्यादि । शेषं वारिवत् । पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न पुंवत् । प्रवृत्तिनिमित्तभेदात् ।

३२२ । अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः । ७ । १ । ७५ । एषामनङ् स्याट्टादावचि, स चोदात्तः । 'अल्लोपोऽनः' (सू २३४) । दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नाम् । दध्नि-दधनि । दध्नोः । शेषं वारिवत् । एवमस्थिसक्थ्यक्षीणि । तदन्तस्याप्यनङ् । अतिदध्ना । सुधि । सुधिनी । सुधीनि । हे सुधे-हे सुधि । सुधिया-सुधिना । सुधियाम्-सुधीनाम् । प्रध्या-प्रधिना । मधु । मधुनी । मधूनि । हे मधो-हे मधु । एवमम्ब्वादयः । 'सानु'शब्दस्य 'स्नु' वा । स्नूनि-सानूनि । प्रियक्रोष्टु । प्रियक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा-प्रियक्रोष्टुना । प्रियक्रोष्ट्रे-प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्र-

तिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । 'नुमचिर–' (वा ४३७४) इति नुट् । प्रियक्रोष्टूनाम् । सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् । सुल्वा–सुलुना । धातृ । धातृणी । धातॄणि । हे धातः–ह धातृ । धात्रा–धातृणा । एवं ज्ञातृकर्त्रादयः ।

३२३ । एच इग्घ्रस्वादेशे । १ । १ । ४८ । आदिश्यमानेषु ह्रस्वेषु मध्य एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि । इह न पुंवत् । यदिगन्तं 'प्रद्यु' इति तस्य भाषितपुंस्कत्वाभावात् । एवमग्रेऽपि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतस्यानन्यत्वात् 'रायो हलि' (सू २८६) इत्यात्वम् । प्रराभ्याम् । प्रराभिः । 'नुमचिर–' (वा ४३७४) इति नुटचात्वे 'प्रराणाम्' इति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुटचात्वं न । 'नामि' (सू २०९) इति दीर्घस्त्वारम्भसामर्थ्यात्संनिपातपरिभाषां बाधत इत्युक्तम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने इत्यादि ।

इत्यजन्तनपुंसकलिङ्गप्रकरणम् ।

अथ हलन्तपुंलिङ्गप्रकरणम् ।

३२४ । हो ढः । ८ । २ । ३१ । हस्य ढः स्याज्झलि पदान्ते च । 'हल्ङ्याप्–' (सू २५२) इति सुलोपः । पदान्तत्वाद्धस्य ढः । जश्त्वचर्त्वे । लिट्–लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु–लिट्सु ।

३२५ । दादेर्धातोर्घः । ८ । २ । ३२ । उपदेशे दादेर्धातोर्हस्य घः स्याज्झलि पदान्ते च । 'उपदेशे' किम् । 'अधोक्' इत्यत्र यथा स्यात् । दामलिहमात्मानमिच्छति दामलिह्यति । ततः क्विपि दामलिट् । अत्र मा भूत् ।

३२६ । एकाचो बशो भष् झषन्तस्य स्ध्वोः । ८ । २ । ३७ । धातोरवयवो य एकाच् झषन्तस्तदवयवस्य बशः स्थाने भष् स्यात्सकारे ध्वशब्दे पदान्ते च । 'एकाचो धातोः' इति सामानाधिकरण्येनान्वये त्विह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः क्विप् । णिलोपः । गर्धप् । 'झलि' इति निवृत्तम् । स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भभावः । जश्त्वचर्त्वे । धुक्–धुग् । दुहौ । दुहः । षत्वचर्त्वे । धुक्षु ।

३२७ । वा द्रुहमुहष्णुहष्णिहाम् । ८ । २ । ३३ । एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक्–ध्रुग्–ध्रुट्–ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम्–ध्रुड्भ्याम् । ध्रुक्षु–ध्रुट्त्सु–ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ।

३२८ । इग्यणः संप्रसारणम् । १ । १ । ४५ । यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ।

३२९ । वाह ऊठ् । ६ । ४ । १३२ । भस्य वाहः संप्रसारणमूठ् स्यात् ।

३३० । संप्रसारणाच्च । ६ । १ । १०८ । संप्रसारणादचि पूर्वरूपमेकादेशः स्यात् । 'एत्येधत्यूठ्सु' (सू ७३) । विश्वौहः । विश्वौहेत्यादि । 'छन्दस्येव ण्विः' इति पक्षे णिजन्ताद्विच् ।

३३१ । चतुरनडुहोरामुदात्तः । ७ । १ । ९८ । अनयोराम् स्यात्सर्वनामस्थाने परे । स चोदात्तः ।

३३२। सावनडुहः। ७। १। ८२। अस्य नुम् स्यात्सौ परे। 'आत्' इत्यधिकारादचो-ऽन्त्यात्परोऽयं नुम्। अतो विशेषविहितेनापि नुमा न बाध्यते। अमा च नुम् बाध्यते। सौर्लोपः। नुम्विधिसामर्थ्यात् 'वसुस्रंसु-' (सू ३३४) इति दत्वं न। संयोगान्तलोपस्यासिद्धत्वान्नलोपो न। अनड्वान्।

३३३। अम् संबुद्धौ। ७। १। ९९। चतुरनडुहोरम् स्यात्संबुद्धौ। आमोऽपवादः। हे अनड्वन्। अनड्वाहौ। अनड्वाहः। अनडुहः। अनडुहा।

३३४। वसुस्रंसुध्वंस्वनडुहां दः। ८। २। ७२। सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। अनडुद्भ्यामित्यादि। 'सान्त-' इति किम्। विद्वान्। 'पदान्ते' इति किम्। स्रस्तम्। ध्वस्तम्।

३३५। सहेः साडः सः। ८। ३। ५६। साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात्। तुराषाट्-तुराषाड्। तुरासाहौ। तुरासाहः। तुराषाड्भ्यामित्यादि। 'तुरं सहते' इत्यर्थे 'छन्दसि सहः' (सू ३४०९) इति ण्विः। लोके तु साहयतेः क्विप्। 'अन्येषामपि-' (सू ३५३९) इति पूर्वपदस्य दीर्घः।

३३६। दिव औत्। ७। १। ८४। दिविति प्रातिपदिकस्य औत्स्यात्सौ परे। अल्विधित्वेन स्थानिवत्त्वाभावात् 'हल्ङ्याप्-' (सू २५२) इति सुलोपो न। सुद्यौः। सुदिवौ। सुदिवः। सुदिवम्। सुदिवौ।

३३७। दिव उत्। ६। १। १३१। दिवोऽन्तादेश उकारः स्यात्पदान्ते। सुद्युभ्याम्। सुद्युभिः। चत्वारः। चतुरः। चतुर्भिः। चतुर्भ्यः। चतुर्भ्यः।

३३८। षट्चतुर्भ्यश्च। ७। १। ५५। षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात्। णत्वम्। द्वित्वम्। चतुर्ण्णाम्।

३३९। रोः सुपि। ८। ३। १६। सप्तमीबहुवचने रोरेव विसर्जनीयो नान्यरेफस्य। षत्वम्। षस्य द्वित्वे प्राप्ते।

३४०। शरोऽचि। ८। ४। ४९। अचि परे शरो न द्वे स्तः। चतुर्षु। प्रियचत्वाः। हे प्रियचत्वः। प्रियचत्वारौ। प्रियचत्वारः। गौणत्वे तु नुट् नेष्यते। प्रियचतुराम्। प्राधान्ये तु स्यादेव। परमचतुर्णाम्। कमलं कमलां वाचष्टे इति कमल्। कमलौ। कमलः। षत्वम्। कमल्षु।

३४१। मो नो धातोः। ८। २। ६४। धातोर्मस्य नः स्यात्पदान्ते। नत्वस्यासिद्धत्वान्नलोपो न। प्रशाम्यतीति प्रशान्। प्रशामौ। प्रशामः। प्रशान्भ्यामित्यादि।

३४२। किमः कः। ७। २। १०३। किमः कः स्याद्विभक्तौ। अकच्सहितस्याप्ययमादेशः। कः। कौ। के। कम्। कौ। कानित्यादि सर्ववत्।

३४३। इदमो मः। ७। २। १०८। इदमो मस्य मः स्यात्सौ परे। त्यदाद्यत्वापवादः।

३४४। इदोऽय् पुंसि। ७। २। १११। इदम इदोऽय् स्यात्सौ पुंसि। सोर्लोपः। अयम्। त्यदाद्यत्वं पररूपत्वं च।

३४५। दश्च। ७। २। १०९। इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। 'त्यदादेः संबोधनं नास्ति' इत्युत्सर्गः।

३४६ । अनाप्यकः । ७ । २ । ११२ । अककारस्येदम इदोऽन् स्यादापि विभक्तौ । 'आप्' इति 'टा' इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ।

३४७ । हलि लोपः । ७ । २ । ११३ । अककारस्येदम इदो लोपः स्यादापि हलादौ । 'नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे' (वा ४९०) ।

३४८ । आद्यन्तवदेकस्मिन् १ । १ । २१ । एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात् । आभ्याम् ।

३४९ । नेदमदसोरकोः । ७ । १ । ११ । अककारयोरिदमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् ङेः स्मै । पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु । ककारयोगे त्वयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ।

३५० । इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ । २ । ४ । ३२ । अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेशः स्यात्तृतीयादौ । अशूवचनं साकच्कार्थम् ।

३५१ । द्वितीयाटौस्स्वेनः । २ । ४ । ३४ । द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । 'किंचित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः' । यथा 'अनेन व्याकरणमधीतम्' 'एनं छन्दोऽध्यापय' इति । 'अनयोः पवित्रं कुलम्' 'एनयोः प्रभूतं स्वम्' इति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ट्सु-सुगण्ट्सु-सुगण्सु । क्विप् । 'अनुनासिकस्य क्विझलोः-' (सू २६६६) इति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ट्सु -सुगाण्ट्सु-सुगाण्सु । परत्वादुपधादीर्घः । हल्ङ्यादिलोपः । ततो नलोपः । राजा ।

३५२ । न ङिसंबुद्ध्योः । ८ । २ । ८ । नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । 'सुपां सुलुक्-' (सू ३५६१) इति ङेर्लुक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । 'परमे व्योमन्' । 'ङावुत्तरपदे प्रतिषेधो वक्तव्यः' (वा ४७८९) । ङौ विषय उत्तरपदे परे 'न ङिसंबुद्ध्योः' (सू ३५२) इत्यस्य निषेधो वाच्य इत्यर्थः । चर्मणि तिला अस्य चर्मतिलः । ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ । 'अल्लोपोऽनः' (सू २३४) अल्लत्वम् । न चाल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नापि बहिरङ्गतयासिद्धः । यथोद्देशपक्षे षाष्ठीं परिभाषां प्रति श्चुत्वस्यासिद्धतयान्तरङ्गाभावे परिभाषाया अप्रवृत्तेः । जञोर्ज्ञः । राज्ञः । राज्ञा ।

३५३ । नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । ८ । २ । २ । सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपोऽसिद्धः । नान्यत्र 'राजाश्वः' इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभिः । राज्ञे । राजभ्याम् । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि । प्रतिदीव्यतीति प्रतिदिवा । प्रतिदिवानौ । प्रतिदिवानः । अस्य भविषयेऽल्लोपे कृते ।

३५४ । हलि च । ८ । २ । ७७ । रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धलि ।

न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि । यज्वा । यज्वानौ । यज्वानः ।

३५५ । न संयोगाद्वमन्तात् । ६ । ४ । १३७ । वकारमकारान्तसंयोगात्परस्यानोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ।

३५६ । इन्हन्पूषार्यम्णां शौ । ६ । ४ । १२ । एषां शावेवोपधाया दीर्घः । नान्यत्र । इति निषेधे प्राप्ते ।

३५७ । सौ च । ६ । ४ । १३ । इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । 'एकाजुत्तरपदे–' (सू ३०७) इति णत्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ।

३५८ । हो हन्तेर्ञ्णिन्नेषु । ७ । ३ । ५४ । ञिति णिति च प्रत्यये, नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ।

३५९ । हन्तेः– । उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं स्यात् । प्रहण्यात् ।

–अत्पूर्वस्य । ८ । ४ । २२ । हन्तेरत्पूर्वस्यैव नस्य णत्वम् । नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यात् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (प ६२) इति न्यायं बाधित्वा 'एकाजुत्तरपदे –' (सू ३०७) इति णत्वमपि निवर्तते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्नेत्यादि । यत्तु 'वृत्रघ्नः' इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं, तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङ्गिन् यशस्विन् अर्यमन् पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि 'इन्हन्–' (सू ३५६) इत्यत्र ग्रहणं भवत्येव । 'अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति' (प १७) इति वचनात् । अर्यम्णि–अर्यमणि । पूष्णि । पूषणि ।

३६० । मघवा बहुलम् । ६ । ४ । १२८ । 'मघवन्'शब्दस्य वा 'तृ' इत्यन्तादेशः स्यात् । ऋ इत् ।

३६१ । उगिदचां सर्वनामस्थानेऽधातोः । ७ । १ । ७० । अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वं न भवति बहुलग्रहणात् । तथा च 'श्वन्नुक्षन्–' (उ १५७) इति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे । 'हविर्जक्षिति निःशङ्को मखेषु मघवानसौ' इति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे मघवा । 'छन्दसीवनिपौ च' इति वनिबन्तं मध्योदात्तं छन्दस्येव । अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ।

३६२ । श्वयुवमघोनामतद्धिते । ६ । ४ । १३३ । अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । 'संप्रसारणाच्च' (सू ३३०) । 'आद्गुणः' (सू ६९) । मघोनः । 'अन्नन्तानाम्' किम् । मघवतः । मघवता । स्त्रियां मघवती । 'अतद्धिते' किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । 'युवन्'शब्दे वस्योत्वे कृते ।

३६३ । न संप्रसारणे संप्रसारणम् । ६ । १ । ३७ । संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ।

३६४ । अर्वणस्त्रसावनञः । ६ । ४ । १२७ । नञा रहितस्यार्वन्नित्यस्याङ्गस्य 'तृ' इत्यन्तादेशः स्यात्, न तु सौ । उगित्त्वान्नुम् । अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वद्भ्यामित्यादि । 'अनञः' किम् । 'अनर्वा' 'यज्व'वत् ।

३६५ । पथिमथ्यृभुक्षामात् । ७ । १ । ८५ । एषामाकारोऽन्तादेशः स्यात्सौ परे । 'आ आत्' इति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ।

३६६ । इतोऽत्सर्वनामस्थाने । ७ । १ । ८६ । पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ।

३६७ । थो न्थः । ७ । १ । ८७ । पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्थाः । पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ।

३६८ । भस्य टेर्लोपः । ७ । १ । ८८ । भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाट्टिलोपः । सुपथी नगरी । अनृभुक्षी सेना । आत्वं नपुंसके न भवति 'न लुमता–' (सू २६३) इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् । 'संबुद्धौ नपुंसकानां नलोपो वा वाच्यः' (वा ४७८६) । हे सुपथिन्–हे सुपथि । 'नलोपः सुप्स्वर–' (सू ३५३) इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात्सुपन्थानि । पुनरपि सुपथि । सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ।

३६९ । ष्णान्ता षट् । १ । १ । २४ । षान्ता नान्ता च संख्या षट्संज्ञा स्यात् । 'षड्भ्यो लुक्' (सू २६१) । पञ्च । पञ्च । 'संख्या' किम् । विप्रुषः । पामानः । 'शतानि' 'सहस्राणि' इत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्य । पञ्चभ्यः । 'षट्चतुर्भ्यश्च' (सू ३३८) इति नुट् ।

३७० । नोपधायाः । ६ । ४ । ७ । नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुग्नुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चनाम् । एवं सप्तन् नवन् दशन् ।

३७१ । अष्टन आ विभक्तौ । ७ । २ । ८४ । अष्टन आत्वं स्याद्धलादौ विभक्तौ ।

३७२ । अष्टाभ्य औश् । ७ । १ । २१ । कृताकारादष्टनः परयोर्जस्शसोरौश् स्यात् । 'अष्टभ्यः' इति वक्तव्ये कृतात्वनिर्देशो जस्शसोर्विषय आत्वं ज्ञापयति । 'वैकल्पिकं चेदमष्टन आत्वम्' । 'अष्टनो दीर्घात्' (सू ३७१८) इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि । पञ्चवत् । गौणत्वे त्वात्वाभावे राजवत् । शासि प्रियाष्टः । इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाच्च । प्रियाष्टा इत्यादि । जस्शसोरनुमीयमानमात्वं प्राधान्य एव । न तु गौणतायाम् । तेन प्रियाष्टौ हलादावेव वैकल्पिकमात्वम् । प्रियाष्टाभ्याम् । प्रियाष्टाभिः । प्रियाष्टाभ्यः । प्रियाष्टाभ्यः । प्रियाष्टासु ।

भियाष्टौ राजवत्सर्वं हाहावशापरं हलि ।

भ्भावः । जश्त्वचर्त्वे । भुत्-भुद् । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुत्सु ।

३७३ । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च । ३ । २ । ५९ । एभ्यः क्विन्स्यात् ।
अलाक्षणिकमपि किंचित्कार्यं निपातनाल्लभ्यते । निरुपपदाद्युजेः क्विन् । कनावितौ ।

३७४ । कृदतिङ् । ३ । १ । ९३ । संनिहिते धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ।

३७५ । वेरपृक्तस्य । ६ । १ । ६७ । अपृक्तस्य वेर्लोपः स्यात् । 'कृत्तद्धित–' (सू १७९)
इति प्रातिपदिकत्वात्स्वादयः ।

३७६ । युजेरसमासे । ७ । १ । ७१ । युजेः सर्वनामस्थाने नुम्स्यादसमासे । सुलोपः ।
'संयोगान्तस्य लोपः' (सू ५४) ।

३७७ । क्विन्प्रत्ययस्य कुः । ८ । २ । ६२ । क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः
स्यात्पदान्ते । नस्य कुत्वेनानुनासिको ङकारः । युङ् । 'नश्चापदान्तस्य–' (सू १२३) इति
नुमोऽनुस्वारः परसवर्णः । तस्यासिद्धत्वात् 'चोः कुः' (सू ३७८) इति कुत्व न । युञ्जौ ।
युञ्जः । युञ्जम् । युञ्जौ । युजः । युजा । युग्भ्यामित्यादि । 'असमासे' किम् ।

३७८ । चोः कुः । ८ । २ । ३० । चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । इति
कुत्वम् । 'क्विन्प्रत्ययस्य–' (सू ३७७) इति कुत्वस्यासिद्धत्वात् । सुयुक्-सुयुग् । सुयुजौ ।
सुयुजः । 'युजेः' इति धातुपाठपठितेकारविशिष्टस्यानुकरणम् । न त्विका निर्देशः । तेनेह
न । युज्यते समाधत्त इति युक् । 'युज् समाधौ' दैवादिक आत्मनेपदी । संयोगान्तलोपः ।
खन् । खञ्जौ । खञ्ज इत्यादि । 'व्रश्च–' (सू २९४) इति षत्वम् । जश्त्वचर्त्वे । राट्-राड् ।
राजौ । राजः । राट्त्सु-राट्सु । एवं विभ्राट् । देवेट् । देवेजौ । देवेजः । विश्वसृट्-विश्वसृड् ।
विश्वसृजौ । विश्वसृजः । इह मृजियज्योः कुत्वं नेति क्वौ वक्ष्यते । परिमृट् । षत्वविधौ
राजिसाहचर्यात् 'टुभ्राजृ दीप्तौ' इति फणादिरेव गृह्यते । यस्तु 'एजृ भ्रेजृ भ्राजृ दीप्तौ' इति
तस्य कुत्वमेव । विभ्राक्-विभ्राग् । विभ्राग्भ्यामित्यादि । 'परौ व्रजेः षः पदान्ते' (उ २१७) ।
परावुपपदे व्रजेः क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् ।
परिव्राजौ । परिव्राजः ।

३७९ । विश्वस्य वसुराटोः । ६ । ३ । १२८ । विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ
राट्शब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमवि-
वक्षितम् । विश्वाराट्-विश्वाराड् । विश्वराजौ । विश्वराजः । विश्वाराड्भ्यामित्यादि ।

३८० । स्कोः संयोगाद्योरन्ते च । ८ । २ । २९ । पदान्ते झलि च परे यः संयोगस्त-
दाद्योः सकारककारयोर्लोपः स्यात् । भृट्-भृड् । सस्य श्चुत्वेन शः । तस्य जश्त्वेन
जः । भृज्जौ । भृज्जः । 'ऋत्विग्–' (सू ३७३) इत्यादिना ऋतावुपपदे यजेः क्विन्
क्विन्नन्तत्वात्कुत्वम् । ऋत्विक्-ऋत्विग् । ऋत्विजौ । ऋत्विजः । 'रात्सस्य' (सू २८०) इति निय-
मात्र संयोगान्तलोपः । ऊर्क्-ऊर्ग् । ऊर्जौ । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ।

३८१ । तदोः सः सावनन्त्ययोः । ७ । २ । १०६ । त्यदादीनां तकारदकारयोरन-
न्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः
परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । न च तकारोच्चारणसामर्थ्यान्नो

वाच्यम्। अतित्वमिति गौणं चरितार्थत्वात्। संज्ञायां गौणत्वे त्वात्वसत्वे न। त्यद्। त्यदौ। त्यदः। अतित्यद्। अतित्यदौ। अतित्यदः। यः। यौ। ये। एषः। एतौ। एते। अन्वादेशे तु एनम्। एनौ। एनान्। एनेन। एनयोः। एनयोः।

३८२। ङेप्रथमयोरम्। ७। १। २८। युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात्।

३८३। मपर्यन्तस्य। ७। २। ९१। इत्यधिकृत्य।

३८४। त्वाहौ सौ। ७। २। ९४। युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे।

३८५। शेषे लोपः। ७। २। ९०। आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात्। 'अतो गुणे' (सू १९१)। 'अमि पूर्वः' (सू १९४) त्वम्। अहम्। ननु 'त्वम् स्त्री' 'अहम् स्त्री' इत्यत्र 'त्व अम्' 'अह अम्' इति स्थिते अमि पूर्वरूपत्वं परमपि बाधित्वान्तरङ्गत्वाट्टाप् प्राप्नोति। सत्यम्। अलिङ्गे युष्मदस्मदी। तेन स्त्रीत्वाभावान्न टाप्। यद्वा। शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया। तेन मपर्यन्ताच्छेषस्य 'अद्' इत्यस्य लोपः स्यात्। स च परोऽप्यन्तरङ्गेऽतो गुणे कृते प्रवर्तते। अदन्तत्वाभावान्न टाप्। परमत्वम्। परमाहम्। अतित्वम्। अत्यहम्।

३८६। युवावौ द्विवचने। ७। २। ९२। द्वयोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ।

३८७। प्रथमायाश्च द्विवचने भाषायाम्। ७। २। ८८। इह युष्मदस्मदोराकारोऽन्तादेशः स्यात्। युवाम्। आवाम्। 'औङि' इत्येव सुवचम्। 'भाषायाम्' किम्। 'युवं वस्त्राणि'। 'मपर्यन्तस्य'(सू ३८३) किम्। साकच्कस्य मा भूत्। युवकाम्। आवकाम्। 'त्वया' 'मया' इत्यत्र 'त्व्या' 'म्या' इति मा भूत्। 'युवकाभ्याम्' 'आवकाभ्याम्' इति च न सिध्येत्।

३८८। यूयवयौ जसि। ७। २। ९३। स्पष्टम्। यूयम्। वयम्। परमयूयम्। परमवयम्। अतियूयम्। अतिवयम्। इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शीः प्राप्तः। 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्'(प ९३) इति न भवति। 'ङेप्रथमयोः–'(सू ३८२) इत्यत्र मकारान्तरं प्रश्लिष्य 'अम् मान्त एवावशिष्यते, न तु विक्रियते' इति व्याख्यानाद्वा।

३८९। त्वमावेकवचने। ७। २। ९७। एकस्योक्तौ युस्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ।

३९०। द्वितीयायां च। ७। २। ८७। युष्मदस्मदोराकारः स्यात्। त्वाम्। माम्। युवाम्। आवाम्।

३९१। शसो न। ७। १। २९। नेत्यविभक्तिकम्। युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात्। अमोऽपवादः। 'आदेः परस्य' (सू ४४)। 'संयोगान्तस्य लोपः' (सू ५४)। युष्मान्। अस्मान्।

३९२। योऽचि। ७। २। ८९। अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः। त्वया। मया।

३९३। युष्मदस्मदोरनादेशे। ७।२।८६। अनयोराकारः स्यादनादेशे हलादौ परे। युवाभ्याम्। आवाभ्याम्। युष्माभिः। अस्माभिः।

३९४। तुभ्यमह्यौ ङयि। ७।२।९५। अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि। अमादेशः। 'शेषे लोपः' (सू ३८५)। तुभ्यम्। मह्यम्। परमतुभ्यम्। परममह्यम्। अतितुभ्यम्। अतिमह्यम्। युवाभ्याम्। आवाभ्याम्।

३९५। भ्यसो भ्यम्। ७।१।३०। भ्यसो भ्यम् अभ्यम् वादेशः स्यात्। आद्यः शेषे लोपस्यान्त्यलोपत्व एव। तत्राङ्गवृत्तपरिभाषयैत्वं न। अभ्यम् तु पक्षद्वयेऽपि साधुः। युष्मभ्यम्। अस्मभ्यम्।

३९६। एकवचनस्य च। ७।१।३२। आभ्यां पञ्चम्येकवचनस्यात्स्यात्। त्वत्। मत्। 'ङसेश्च' इति सुवचम्। युवाभ्याम्। आवाभ्याम्।

३९७। पञ्चम्या अत्। ७।१।३१। आभ्यां पञ्चम्या भ्यसोऽत्स्यात्। युष्मत्। अस्मत्।

३९८ तवममौ ङसि। ७।२।९६। अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि।

३९९। युष्मदस्मद्भ्यां ङसोऽश्। ७।१।२७। स्पष्टम्। तव। मम। युवयोः। आवयोः।

४००। साम आकम्। ७।१।३३। आभ्यां परस्य साम आकम् स्यात्। भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः। युष्माकम्। अस्माकम्। त्वयि। मयि। युवयोः। आवयोः। युष्मासु। अस्मासु।

समस्यमाने द्व्येकत्ववाचिनी युष्मदस्मदी।
समासार्थोऽन्यसंख्यश्चेत्स्तो युवावौ त्वमावपि॥
सुजस्ङेङस्सु परत आदेशाः स्युः सदैव ते।
त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावपि॥
एते परत्वाद्बाधन्ते युवावौ विषये स्वके।
त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः॥
द्व्येकसंख्यः समासार्थो बह्वर्थे युष्मदस्मदी।
तयोरद्व्येकतार्थत्वान्न युवावौ त्वमौ न च॥

त्वां मां वा अतिक्रान्त इति विग्रहे अतित्वम्। अत्यहम्। अतित्वाम्। अतिमाम्। अतियूयम्। अतिवयम्। अतित्वाम्। अतिमाम्। अतित्वाम्। अतिमाम्। अतित्वान्। अतिमान्। अतित्वया। अतिमया। अतित्वाभ्याम्। अतिमाभ्याम्। अतित्वाभिः। अतिमाभिः। अतितुभ्यम्। अतिमह्यम्। अतित्वाभ्याम्। अतिमाभ्याम्। अतित्वभ्यम्। अतिमभ्यम्। ङसिभ्यसोः। अतित्वत्। अतित्वत्। अतिमत्। अतिमत्। भ्यामि प्राग्वत्। अतितव। अतिमम। अतित्वयोः। अतिमयोः। अतित्वाकम्। अतिमाकम्। अतित्वयि। अतिमयि। अतित्वयोः। अतिमयोः। अतित्वासु। अतिमासु। युवाम् आवां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत्। औअमौट्सु। अतियुवाम्। अतियुवाम्। अतियुवाम्। अत्यावाम्। अत्यावाम्। अत्यावाम्। अतियुवान्। अत्यावान्। अतियुवया। अत्यावया। अतियुवाभ्याम्।

अत्यावाभ्याम् । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् । अतियुवत् । अत्यावत् । अत्यावत् । ओसि । अतियुवयोः । अतियुवयोः । अत्यावयोः । अत्यावयोः । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वातिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअम्औट्सु । अतियुष्माम् । अतियुष्माम् । अतियुष्माम् । अत्यस्माम् । अत्यस्माम् । अत्यस्माम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् । अत्यस्माभ्याम् । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् । अत्यस्मत् । ओसि । अतियुष्मयोः । अतियुष्मयोः । अत्यस्मयोः । अत्यस्मयोः । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ।

४०१ । पदस्य । ८ । १ । १६ ।

४०२ । पदात् । ८ । १ । १७ ।

४०३ । अनुदात्तं सर्वमपादादौ । ८ । १ । १८ । इत्यधिकृत्य ।

४०४ । युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ । ८ । १ । २० । पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनौ इत्यादेशौ स्तः । तौ चानुदात्तौ ।

४०५ । बहुवचनस्य वस्नसौ । ८ । १ । २१ । उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः । वान्नावोरपवादः ।

४०६ । तेमयावेकवचनस्य । ८ । १ । २२ । उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ।

४०७ । त्वामौ द्वितीयायाः । ८ । १ । २३ । द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ।

> श्रीशस्त्वावतु मापीह दत्तात्ते मेऽपि शर्म सः ।
> स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥
> सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।
> सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥

'पदात्परयोः' किम् । वाक्यादौ मा भूत् । त्वां पातु । मां पातु । 'अपादादौ' किम् । 'वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदावतु' । स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति । 'समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' (वा ४७१४) । 'एकतिङ् वाक्यम्' (वा ११९९) । तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । 'शालीनां ते ओदनं दास्यामि' इति । 'एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः' (वा ४७१७) । अन्वादेशे तु नित्यं स्युः धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ।

४०८ । न चवाहाहैवयुक्ते । ८ । १ । २४ । चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः । परम्परासंबन्धे त्वादेशः स्यादेव । हरौ हरिश्च मे स्वामी ।

४०९ । पश्यार्थैश्चानालोचने । ८ । १ । २५ । अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते

आदेशा न स्युः । चेतसा त्वां समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु भक्तस्त्वा पश्यति चक्षुषा ।

४१० । सपूर्वायाः प्रथमाया विभाषा । ८ । १ । २६ । विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा वा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मा इति वा ।

४११ । सामन्त्रितम् । २ । ३ । ४८ । संबोधने या प्रथमा तदन्तमामन्त्रितसंज्ञं स्यात् ।

४१२ । आमन्त्रितं पूर्वमविद्यमानवत् । ८ । १ । ७२ । स्पष्टम् । अग्ने तव । देवास्मान्पाहि । अग्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशास्तिङन्तनिघात आमन्त्रितनिघातश्च न । 'सर्वदा रक्ष देव नः' इत्यत्र तु देवेत्यस्याविद्यमानवत्त्वेऽपि तन्प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवम् 'इमं मे गङ्गे यमुने' इति मन्त्रे यमुन इत्यादीनामामन्त्रितानामविद्यमानवत्त्वेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः ।

४१३ । नामन्त्रिते समानाधिकरणे सामान्यवचनम् । ८ । १ । ७३ । विशेष्यं समानाधिकरणे विशेषण आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालो नः पाहि । अग्ने तेजस्विन् । 'विभाषितं विशेषवचने' (सू ३६९९) । अत्र भाष्यम् । बहुवचनमिति वक्ष्यामि । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परेऽविद्यमानवद्वा । यूयं प्रभवः देवाः शरण्या युष्मान्भजे । वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात्-सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ।

४१४ । पादः पत् । ६ । ४ । १३० । पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपाद्भ्यामित्यादि । अग्निं मन्थतीत्यग्निमत्-अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमद्भ्यामित्यादि । 'ऋत्विग्-' (सू ३७३)आदिसूत्रेणाञ्चेः सुप्युपपदे क्विन् ।

४१५ । अनिदितां हल उपधायाः क्ङिति । ६ । ४ । २४ । हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । 'उगिदचाम्-' (सू ३६१) इति नुम् । 'संयोगान्तस्य लोपः' (सू ५४) । नुमो नकारस्य 'क्विन्प्रत्ययस्य कुः' (सू ३७७) इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णौ । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ।

४१६ । अचः । ६ । ४ । १३८ । लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ।

४१७ । चौ । ६ । ३ । १३८ । लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । 'अचः' (सू ४१६) इति लोपस्य विषयेऽन्तरङ्गेऽपि यण् न प्रवर्तते । 'अकृतव्यूहाः-' (प ५७) इति परिभाषया । प्रतीचः । प्रतीचा । 'अमुमञ्चति' इति विग्रहे 'अदस् अञ्च्' इति स्थिते ।

४१८ । विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये । ६ । ३ । ९२ । अनयोः सर्वनाम्नश्च टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । 'अदद्रिअञ्च्' इति स्थिते यण् ।

४१९ । अदसोऽसेर्दादु दो मः । ८ । २ । ८० । अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च । उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्ध्रस्वव्यञ्जनयोर्ह्रस्वो

दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयञ्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यामित्यादि । मुत्वस्यासिद्धत्वान्न यण् । 'अन्त्यबाधेऽन्त्यसदेशस्य' (प १०४) इति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते 'अदमुयङ्' । 'अः सेः सकारस्य स्थाने यस्य सः असिः' इति व्याख्यानान्तरे 'त्यदाद्यत्वविषय एव मुत्वं नान्यत्र' इति पक्षे 'अदद्र्यङ्' । उक्तं च [भाष्ये] ।

'अदसोऽद्रेः पृथङ्मुत्वं केचिदिच्छन्ति लत्ववत् ।
केचिदन्त्यसदेशस्य नेत्येकेऽसेर्हि दृश्यते ॥'

इति । 'विष्वग्देवयोः' किम् । अश्वाची । 'अञ्चतौ' किम् । विष्वग्युक् । 'अप्रत्यये' किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति 'अन्यत्र धातुग्रहणे तदादिविधिः' इति । तेनायस्कारः । 'अतः कृकमि–' (सू १६०) इति सः । उदङ् । उदञ्चौ । उदञ्चः । शसादावचि ।

४२० । उद ईत् । ६ । ४ । १३९ । उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भ्यामित्यादि ।

४२१ । समः समि । ६ । ३ । ९३ । अप्रत्ययान्तेऽञ्चतौ परे समः समिरादेशः स्यात् । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ।

४२२ । सहस्य सध्रिः । ६ । ३ । ९५ । अप्रत्ययान्तेऽञ्चतौ परे । सध्र्यङ् ।

४२३ । तिरसस्तिर्यलोपे । ६ । ३ । ९४ । अलुप्ताकारेऽञ्चतावप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि ।

४२४ । नाञ्चेः पूजायाम् । ६ । ४ । ३० । पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न । प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्खु–प्राङ्क्षु–प्राङ्षु । एवं पूजार्थे प्रत्यङ्ङादयः । 'क्रुञ्च कौटिल्याल्पीभावयोः' । अस्य 'ऋत्विग्–'(सू ३७३)आदिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुङ्भ्यामित्यादि । 'चोः कुः' (सू ३७८) पयोमुक् पयोमुग् । पयोमुचौ । पयोमुचः । 'व्रश्च–' (सू २९४) इति षत्वम् । 'स्कोः–' (सू ३८०) इति सलोपः । जश्त्वचर्त्वे । सुवृट्–सुवृड् । सुवृश्चौ । सुवृश्चः । सुवृट्त्सु–सुवृट्सु । 'वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च' (उ २४१) एते निपात्यन्ते, शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् । 'सान्तमहतः–' (सू ३१७) इति दीर्घः । मह्यते पूज्यत इति महान् । महान्तौ । महान्तः । हे महन् । महतः । महता । महद्भ्यामित्यादि ।

४२५ । अत्वसन्तस्य चाधातोः । ६ । ४ । १४ । अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वा वचनसामर्थ्यादादौ दीर्घः । ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानिवाचरतीति वा क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । 'उगिदचाम्–' (सू ३६१) इति सूत्रेऽञ्ग्रहणं नियमार्थम् । 'धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव' इति । तेन 'स्रत्' 'ध्वत्' इत्यादौ न । 'अधातोः' इति त्वधातुभूतपूर्वस्यापि नुमर्थम् ।

गोमान् । गोमन्तौ । गोमन्त इत्यादि । 'भातेर्डवतुः' (उ ६३) । भवान् । भवन्तौ । भवन्तः । शन्नन्तस्य त्वत्वन्तत्वाभावान्न दीर्घः । भवतीति भवन् ।

४२६ । उभे अभ्यस्तम् । ६ । १ । ५ । षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ।

४२७ । नाभ्यस्ताच्छतुः । ७ । १ । ७८ । अभ्यस्तात्परस्य शतुर्नुम्न स्यात् । ददत्-ददद् । ददतौ । ददतः ।

४२८ । जक्षित्यादयः षट् । ६ । १ । ६ । षड् धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत्-जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्ङित्त्वेऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् । गुप्-गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि ।

४२९ । त्यदादिषु दृशोऽनालोचने कञ्च । ३ । २ । ६० । त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेर्धातोः कञ्स्यात् । चात्क्विन् ।

४३० । आ सर्वनाम्नः । ६ । ३ । ९१ । सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । कुत्वस्यासिद्धत्वात् 'व्रश्च-'(सू २९४) इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वेन पक्षे कः । तादृक्-तादृग् । तादृशौ । तादृशः । 'षत्वापवादत्वात्कुत्वेन खकारः' इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयते । न तु गः । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । 'दिगादिभ्यो यत्' (सू १४२९) इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । 'व्रश्च-'(सू २९४) इति षत्वम् । जश्त्वचर्त्वे । विट्-विड् । विशौ । विशः । विशाम् ।

४३१ । नशेर्वा । ८ । २ । ६३ । नशेः कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक्-नग् । नट्-नड् । नशौ । नशः । नग्भ्याम्-नड्भ्यामित्यादि ।

४३२ । स्पृशोऽनुदके क्विन् । ३ । २ । ५८ । अनुदके सुप्युपपदे स्पृशेः क्विन्स्यात् । घृतस्पृक्-घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन्प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात्क्विप्यपि कुत्वम् । स्पृक् । षडगकाः प्राग्वत् । 'ञिधृषा प्रागल्भ्ये' । अस्मात् 'ऋत्विग्-' (सू ३७३) आदिना क्विन् । द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः गः कः । धृष्णोतीति दधृक्-दधृग् । दधृषौ । दधृषः । दधृग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट्-रत्नमुड् । रत्नमुषौ । रत्नमुषः । 'षड्भ्यो लुक्' (सू २६१) । षट्-षड् । षड्भिः । षड्भ्यः । षड्भ्यः । 'षट्चतुर्भ्यश्च' (सू ३३८) इति नुट् । 'अनाम्' इति पर्युदासान्न ष्टुत्वनिषेधः । 'यरोऽनुनासिक-' (सू ११६) इति विकल्पं बाधित्वा 'प्रत्यये भाषायां नित्यम्' (वा५०१७) इति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु-षट्सु । तदन्तविधिः । परमषट् । परमषण्णाम् । गौणत्वे तु प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् 'ससजुषो रुः' (सू १६२) इति रुत्वम् ।

४३३ । र्वोरुपधाया दीर्घ इकः । ८ । २ । ७६ । रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । 'वा शरि' (सू १५१) इति वा विसर्जनीयः ।

४३४ । नुम्विसर्जनीयशर्व्यवायेऽपि । ८ । ३ । ५८ । एतैः प्रत्येकं व्यवधानेऽपि

इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीष्षु–पिपठीःषु । 'प्रत्येकम्' इति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्स्व । निंस्से । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थं व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अत एव न शर्ग्रहणेन गतार्थता । 'रात्सस्य' (सू २८०) इति सलोपे विसर्गः । चिकीः । चिकीर्षौ । चिकीर्षः । 'रोः सुपि' (सू ३३९) इति नियमान्न विसर्गः । चिकीर्षु । 'दमेर्डोसिः' (उ २२७) । डित्त्वसामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्रुत्वविसर्गौ । दोः । दोषौ । दोषः । 'पद्दन्नो–' (सू २२८) इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । 'विश प्रवेशने' । सन्नन्तात्क्विप् । षत्वस्यासिद्धत्वात्संयोगान्तलोपः । 'व्रश्च–' (सू २९४) इति षः । जश्त्वचर्त्वे । विविट्–विविड् । विविक्षौ । विविक्षः । 'स्कोः–' (सू ३८०) इति कलोपः । तट्–तड् । तक्षौ । तक्षः । गोरट्–गोरड् । गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु 'स्कोः–' (सू ३८०) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् । 'पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । 'तस्य दोषः संयोगादिलोपलत्वणत्वेषु' (वा ४४०) इति निषेधात् । तस्मात्संयोगान्तलोप एव । तक्–तग् । गोरक्–गोरग् । 'स्कोः–' (सू ३८०) इति कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोपः । पिपक्–पिपग् । एवं विवक् । दिधक् । 'पिस गतौ' । सुष्ठु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीर्भ्याम् । सुपीष्षु–सुपीःषु । एवं सुतूः । 'तुस खण्डने' । विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । विद्वांसम् । विद्वांसौ ।

४३५ । वसोः संप्रसारणम् । ६ । ४ । १३१ । वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वम् । षत्वम् । विदुषः । विदुषा । 'वसुस्रंसु–' (सू ३३४) इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । 'अकृतव्यूहाः–' (प ५७) इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । 'सान्तमहतः–' (सू ३१७) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते । न तु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु–सुहिन्सु । ध्वत्–ध्वद् । ध्वसौ । ध्वसः । ध्वद्भ्याम् । एवं स्रत् ।

४३६ । पुंसोऽसुङ् । ७ । १ । ८९ । सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । 'बहुपुंसी' इत्यत्र 'उगितश्च' (सू ४५५) इति ङीबर्थं कृतेन 'पूञो डुम्सुन्' ('पातेर्डुम्सुन्')[1] इति प्रत्ययस्योगित्त्वेनैव नुम्सिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । 'ऋदुशन–' (सू २७६) इत्यनङ् । उशना । उशनसौ । उशनसः । 'अस्य संबुद्धौ वानङ् नलोपश्च वा वाच्यः (वा ५०३७) । हे उशनन्–हे उशन–हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातो–

---

१. 'भाष्यानुक्तत्वादिदमप्रमाणमेव' इति प्रामाणिकाः' इति शेखरः । 'सोर्डा' इत्येव सिद्धे अनङ्विधानस्याचानाङि प्रमाणत्वेऽपि नलोपविकल्पो निर्मूलः' इति रत्नाकरः ।

रिन्युक्तेर्न दीर्घः । सुष्ठु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं ग्रसते पिण्डग्रः । पिण्डग्लः । 'ग्रसु ग्लसु अदने' ।

४३७ । अदस औ सुलोपश्च । ७ । २ । १०७ । अदस औकारोऽन्तादेशः स्यात्सौ परे सुलोपश्च । 'तदोः सः सौ–' (सू ३८१) इति दस्य सः । असौ । 'औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च' (वा ४४८२) । प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं पररूपत्वम् । वृद्धिः । 'अदसोऽसेः–' (सू ४१९) इति नत्वोत्वे । अमू । 'जसः शी' (सू २१४) । आद्गुणः' (सू ६९) ।

४३८ । एत ईद्बहुवचने । ८ । २ । ८१ । अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । 'पूर्वत्रासिद्धम्' (सू १२) इति विभक्तिकार्यं प्राक् । पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ।

४३९ । न मु ने । ८ । २ । ३ । नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् । अमूभ्याम् । अमूभ्याम् । अमीभिः । अमुष्मै । अमीभ्यः । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु ।

इति हलन्तपुंलिङ्गप्रकरणम् ।

अथ हलन्तस्त्रीलिङ्गप्रकरणम् ।

४४० । नहो धः । ८ । २ । ३४ । नहो हस्य धः स्याज्झलि पदान्ते च । उपानत्–उपानद् । उपानहौ । उपानहः । उपानद्भ्याम् । उपानत्सु । उत्पूर्वात् 'ष्णिह प्रीतौ' (धा १२०१) इत्यस्मात् 'ऋत्विग्–' (सू ३७३) आदिना क्विन्निपातनाद्धलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक्–उष्णिग् । उष्णिहौ । उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । द्युषु । गीः । गिरौ । गिरः । एवं पूः । चतुरश्चतसृादेशः । चतस्रः । चतस्रः । चतसृणाम् । किमः कादेशे टाप् । का । के । काः । सर्वावत् ।

४४१ । यः सौ । ७ । २ । ११० । इदमो दस्य यः स्यात्सौ । 'इदमो मः' (सू ३४३) । इयम् । त्यदाद्यत्वं टाप् । 'दश्च' (सू ३४५) इति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया । 'हलि लोपः' (सू ३४७) । आभ्याम् । आभ्याम् । आभ्याम् । आभिः । अस्यै । अस्याः । अनयोः । आसाम् । अस्याम् । अनयोः । आसु । अन्वादेशे तु एनाम् । एने । एनाः । एनया । एनयोः । एनयोः । 'ऋत्विग्–'(सू ३७३)आदिना सृजेः क्विन्नमागमश्च निपातितः । स्रक्–स्रग् । स्रजौ । स्रजः । स्रग्भ्याम् । स्रक्षु । त्यदाद्यत्वम् । टाप् । स्या । त्ये । त्याः । एवं तद् यद् एतद् । वाक्–वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु । अप्शब्दो नित्यं बहुवचनान्तः । 'अप्तृन्–' (सू २७७) इति दीर्घः । आपः । अपः ।

४४२ । अपो भि । ७ । ४ । ४८ । अपस्तकारः स्याद्भादौ प्रत्यये परे । अद्भिः । अद्भ्यः । अद्भ्यः । अपाम् । अप्सु । दिक्–दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु । 'त्यदादिषु–' (सू ४२९) इति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक्–दृग् । दृशौ । दृशः ।

त्विट्-त्विड् । त्विषौ । त्विषः । त्विड्भ्याम् । त्विट्त्सु-त्विट्सु । सह जुषत इति सजूः । सजुषौ । सजुषः । सजूर्भ्याम् । सजूःषु-सजूष्षु । षत्वस्यासिद्धत्वाद्रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । आशीर्भिः । असौ । त्यदाद्यत्वं टाप् । औङः शी । उत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः । अमुष्याः । अमुयोः । अमूषाम् । अमुष्याम् । अमुयोः । अमूषु ।

इति हलन्तस्त्रीलिङ्गप्रकरणम् ।

अथ हलन्तनपुंसकलिङ्गप्रकरणम् ।

स्वमोर्लुक् । दत्वम् । स्वनडुत्-स्वनडुद् । स्वनडुही । 'चतुरनडुहो-' (सू ३३१) इत्याम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् । 'दिव उत्' (सू ३३७) । विमलद्यु अहः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पूर्वपदस्येवोत्तरखण्डस्यापि पदसंज्ञायां प्राप्तायाम् 'उत्तरपदत्वे चापदादिविधौ प्रतिषेधः' (वा ४८०) इति प्रत्ययलक्षणं न । विमलदिवी । विमलदिवि । 'अपदादिविधौ' किम् । दधिसेचौ । इह षत्वनिषेधे कर्तव्ये पदत्वमस्त्येव । चत्वारस्य कुत्वे तु न । वाः । वारी । अझलन्तत्वान्न नुम् । वारि । चत्वारि । 'न लुमता-' (सू २६३) इति कादेशो न । किम् । के । कानि । इदम् । इमे । इमानि । 'अन्वादेशे नपुंसके एनद्वक्तव्यः' (वा १५६५) । एनत् । एने । एनानि । एनेन । एनयोः । एनयोः । ब्रह्म । ब्रह्मणी । ब्रह्माणि । हे ब्रह्मन्-हे ब्रह्म । 'रोऽसुपि' (सू १७२) । अहर्भाति । 'विभाषा ङिश्योः' (सू २३७) । अह्नी-अहनी । अहानि ।

४४३ । अहन् । ८ । २ । ६८ । 'अहन्' इत्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह 'अहः' 'अहोभ्याम्' इत्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते 'अहन्' इत्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रुत्वरत्वे । दीर्घाण्यहानि यस्मिन्स दीर्घाहा निदाघः । इह हल्ङ्यादिलोपे प्रत्ययलक्षणेन 'असुपि' इति निषेधाद्रत्वाभावे रुस्तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निदाघ । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डीनि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रह । बहुवृत्रघ्नी-बहुवृत्रहणी । बहुवृत्रहाणि । बहुपूष । बहुपूष्णी-बहुपूषणी । बहुपूषाणि । बह्वर्यम । बह्वर्यम्णी-बह्वर्यमणी । बह्वर्यमाणि । असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । 'सृजिदृशोः-' (सू २४०५) इति सूत्रे 'रज्जुसृड्भ्याम्' इति भाष्यप्रयोगात् । यद्वा 'व्रश्च-' (सू २९४)-आदिसूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । स्रगृत्विक्छब्दयोस्तु निपातनादेव कुत्वम् । असृक्छब्दस्तु असयतेरौणादिके ऋक्प्रत्यये बोध्यः । असृक्-असृग् । असृजी । असृञ्जि । 'पद्दन्-' (सू २२८) इति वा । असन् । असानि । असृजा-अस्ना । असृग्भ्याम्-अस्भ्यामित्यादि । ऊर्क्-ऊर्ग् । ऊर्जी । ऊर्न्जि । नरजानां संयोगः । 'बहूर्जि नुम्प्रतिषेधः' (वा ४३३१) । 'अन्त्यात्पूर्वो वा नुम्' (वा ४३३२) । बहूर्जि-बहूर्न्जि वा कुलानि । त्यत्-त्यद् ।

त्ये त्यानि । तत्–तद् । ते । तानि । यत्–यद् । ये । यानि । एतत्–एतद् । एते । एतानि । अन्वादेशे तु एनत् । बेभिद्यतेः क्विप् । बेभित्–बेभिद् । बेभिदी । शावलोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुन्न, स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि । चेच्छिदि ।

गवाक्छब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः ।
असंध्यवङ्पूर्वरूपैर्नवाधिकशतं मतम् ॥
स्वम्सुप्सु नव षट् भादौ षट्के स्युस्त्रीणि जश्शसोः ।
चत्वारि शेषे दशके रूपाणीति विभावय ॥

तथाहि । गामञ्चतीति विग्रहे 'ऋत्विग्–' (सू ३७३) आदिना क्विन् । गतौ नलोपः । 'अवङ् स्फोटायनस्य' (सू ८८) इत्यवङ् । गवाक्–गवाग् । 'सर्वत्र विभाषा–' (सू ८ इति प्रकृतिभावे । गोअक्–गोअग् । पूर्वरूपे । गोक्–गोग् । पूजायां नस्य कुत्वेन ङः । गवाङ्–गोअङ्–गोङ् । अस्यप्येतान्येव नव । औङः शी । भत्वात् 'अचः' (सू ४१ गवाची–गोअची–गोची । 'जश्शसोः शिः' (सू ३१ इत्यलोपः । गोची । पूजायां तु । गवाञ्ची–गोअञ्ची–गोञ्ची । गतिपूजनयोस्त्रीण्येव । गोचा–गवाञ्चि सर्वनामस्थानत्वान्नुम् । गवाञ्चि–गोअञ्चि–गोञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा–गवाञ्चा गोञ्चा–गोअञ्चा । गवाग्भ्याम्–गोअग्भ्याम्–गोग्भ्याम्–गवाङ्भ्याम्–गोअङ्भ्याम्–गोङ्भ्या मित्यादि । सुपि तु ङन्तानां पक्षे 'ङ्णोः कुक्–' (सू १३०) इति कुक् । गवाङ्क्षु–गोअङ्क्षु गोङ्क्षु–गवाङ्षु–गोअङ्षु–गोङ्षु–गवाक्षु–गोअक्षु–गोक्षु । न चेह 'चयो द्वितीयाः (वा ५०२३) इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्क्यम् । चर्त्वस्यासिद्धत्वात् कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाभावपक्षे चयो द्वितीयादेशात्त्रीणि रूपाणि वर्धन्त एव ।

ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् ।
रूपाण्यथाक्षिभूतानि (५२७) भवन्तीति मनीषिभिः ॥

तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती यकृन्ति । 'पद्दन्–' (सू २२८) इति वा यकन् । यकानि । यक्ना–यकृता । शकृत् । शकृती शकृन्ति । शकानि । शक्ना–शकृता । ददत् । ददती ।

४४४ । वा नपुंसकस्य । ७ । १ । ७९ । अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने । ददन्ति–ददति । तुदत् ।

४४५ । आच्छीनद्योर्नुम् । ७ । १ । ८० । अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम्वा स्याच्छीनद्योः परतः । तुदन्ती–तुदती । तुदन्ति । भात् । भान्ती–भाती भान्ति । पचत् ।

४४६ । शप्श्यनोर्नित्यम् । ७ । १ । ८१ । शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम्स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । स्व स्वप् । स्वपी । नित्यात्परादपि नुमः प्राक् 'अमृन्–' (सू २७७) इति दीर्घः प्रतिपदोक्तत्वा नुम् । स्वाम्पि । 'निरवकाशत्वं प्रतिपदोक्तत्वम्' इति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वाम्पि

स्वपा । 'अपो भि' (सू ४४२) । स्वद्भ्याम् । स्वद्भिः । 'अर्तिपृवपि–' (उ २७५) इत्यादिना धनेरुस् । रुत्वम् । धनुः । धनुषी । 'सान्त–' (सू ३१७) इति दीर्घः । 'नुम्विसर्जनीय–' (सू ४३४) इति षत्वम् । धनूंषि । धनुषा । धनुर्भ्याम् । एवं चक्षुर्हविरादय । पिपठिषतेः क्विप् । 'र्वोः–' (सू ४३३) इति दीर्घः । पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम्न । स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम्न । पिपठिषि । पिपठीर्भ्यामित्यादि पुंवत् । पयः । पयसा । पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ।

इति हलन्तनपुंसकलिङ्गप्रकरणम् ।

अथाव्ययप्रकरणम् ।

४४७ । स्वरादिनिपातमव्ययम् । १ । १ । ३७ । स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् । उच्चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस् । अवस् । समया । निकषा । स्वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । 'वत्' (ग ४) । ब्राह्मणवत् । क्षत्रियवत् । सना । सनत् । सनात् । उपधा । तिरस् । अन्तरा । अन्तरेण । ज्योक् । कम् । शम् । सहसा । विना । नाना । स्वस्ति । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्या । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रवाहुकम् । प्रवाहिका । आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रताम् । प्रशान् । प्रतान् । मा । माङ् । आकृतिगणोऽयम् । च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् । चेत् । चण् । कच्चित् । यत्र । नह । हन्त । माकिः । माकिम् । नकिः । नकिम् । माङ् । नञ् । यावत् । तावत् । त्वै । द्वै । न्वै । रै । श्रौषट् । वौषट् । स्वाहा । स्वधा । वौषट् । तुम् । तथाहि । खलु । किल । अथ । सुष्ठु । स्म । आदह । 'उपसर्गविभक्तिस्वरप्रतिरूपकाश्च' (ग १६) । अवदत्तम् । अहंयुः । अस्तिक्षीरा । अ । आ । इ । ई । उ । ऊ । ए । ऐ ओ । औ । पशु । शुकम् । यथाकथाच । पाट् । प्याट् । अङ्ग । है । हे । भोः । अये । द्य । विषु । एकपदे । पत् । आतः । चादिरप्याकृतिगणः ।

४४८ । तद्धितश्चासर्वविभक्तिः । १ । १ । ३८ । यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक्पाशपः । शस्प्रभृतयः प्राक्समासान्तेभ्यः । अम् । आम् । 'कृत्वोर्थाः' । तसिवती । नानाञाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ।

४४९ । कृन्मेजन्तः । १ । १ । ३९ । कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारंस्मारम् । जीवसे । पिबध्यै ।

४५० । क्त्वातोसुन्कसुनः । १ । १ । ४० । एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः ।

*4

४५१ । अव्ययीभावश्च । १ । १ । ४१ । अधिहरि ।

४५२ । अव्ययादाप्सुपः । २ । ४ । ८२ । अव्ययाद्विहितस्यापः सुपश्च लुक्स्यात् । गो
४५२ । अव्ययादाप्सुपः । २ । ४ । ८२ । अव्ययाद्विहितस्यापः सुपश्च लुक्स्यात् । गो

शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति
तथापि न गौणे । 'आप्ग्रहणं व्यर्थमलिङ्गत्वात्' (वा १६२३) ।

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥

इति [भाष्योक्ता] श्रुतिर्लिङ्गकारकसंख्याभावपरा ।

वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥

वगाहः । अवगाहः । पिधानम् । अपिधानम् ।

इत्यव्ययप्रकरणम् ।

अथ स्त्रीप्रत्ययप्रकरणम् ।

४५३ । स्त्रियाम् । ४ । १ । ३ । अधिकारोऽयम् । समर्थानामिति यावत् ।

४५४ । अजाद्यतष्टाप् । ४ । १ । ४ । अजादीनामकारान्तस्य च वाच्यं यत्स्त्री
तत्र द्योत्ये टाप्स्यात् । अजाद्युक्तिर्ङीषो ङीपश्च बाधनाय । अजा । अतः । खट्वा । अज
दिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । 'द्विगोः' (सू ४७९) इति ङीप् । अत्र हि सम
सार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिल
क्षणो ङीष् प्राप्तः । बाला । वत्सा । होढा । मन्दा । विलाता । एषु 'वयसि प्रथमे' (सू ४७
इति ङीप् प्राप्तः । 'संभस्त्राजिनशणपिण्डेभ्यः फलात्' (वा २४९७) । संफला । भस्त्रफला
'ङ्याापोः–' (सू १००१) इति ह्रस्वः । 'सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्' (वा २४९६)
सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा । 'शूद्रा चामहत्पूर्वा जातिः' (वा २४००–२४०१) । पुंयोगे
तु शूद्री । 'अमहत्पूर्वा' किम् । महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा कनिष्ठा
मध्यमेति पुंयोगेऽपि । कोकिला जातावपि । 'मूलान्नञः' (वा २५००) । अमूला
'ऋन्नेभ्यो ङीप्' (सू ३०६) । कर्त्री । दण्डिनी ।

४५५ । उगितश्च । ४ । १ । ६ । उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात् । पचन्ती
भवन्ती । 'शप्श्यनोः–' (सू ४४६) इति नुम् । 'उगिदचाम्–' (सू ३६१) इति सूत्रेऽज्ग्रह
णेन 'धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव' इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । 'अनि
दिताम्–' (सू ४१५) इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ।

४५६ । वनो र च । ४ । १ । ७ । वन्नन्तात्तदन्ताच्च प्रातिपदिकात्स्त्रियां ङीप्स्यात्
रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिब्वनिपां सामान्यग्रहणम् । 'प्रत्ययग्रहणे यस्मात्स विहि
स्तदादेस्तदन्तस्य ग्रहणम्' (प २४) । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते
सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी । 'वनो न हश इति वक्तव्यम्' (वा
२४०५) । हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकान्ङीब्रश्च नेत्यर्थः

---

१ '('पाककर्ण–'इति प्राप्तस्य ङीषः) प्रतिषेधः' इति वार्तिकशेषः ।

'ओणृ अपनयने' । वनिप् । 'विड्वनोः–' (सू २९८२) इत्यात्त्वम् । अवावा ब्राह्मणी । राजयुध्वा । 'बहुव्रीहौ वा' (वा २४०७) । बहुधीवरी । बहुधीवा । पक्षे डाब्वक्ष्यते ।

४५७ । पादोऽन्यतरस्याम् । ४ । १ । ८ । पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रातिपदिकान्ङीब्वा स्यात् । द्विपदी–द्विपाद् ।

४५८ । टाबृचि । ४ । १ । ९ । ऋचि वाच्यायां पादन्ताट्टाप्स्यात् । द्विपदा ऋक् । एकपदा । 'न षट्स्वस्रादिभ्यः' (सू ३०८) । पञ्च । चतस्रः । 'पञ्च' इत्यत्र नलोपे कृतेऽपि 'ष्णान्ता षट्' (सू ३६९) इति षट्संज्ञां प्रति 'नलोपः सुप्स्वर–' (सू ३९२) इति नलोपस्यासिद्धत्वात् 'न षट्स्वस्रादिभ्यः' (सू ३०८) इति न टाप् ।

४५९ । मनः । ४ । १ । ११ । मन्नन्तान्न ङीप् । सीमा । सीमानौ ।

४६० । अनो बहुव्रीहेः । ४ । १ । १२ । अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ।

४६१ । डाबुभाभ्यामन्यतरस्याम् । ४ । १ । १३ । सूत्रद्वयोपात्ताभ्यां डाब्वा स्यात् । सीमा । सीमे–सीमानौ । दामा । दामे–दामानौ । 'न पुंसि दाम' इत्यमरः । बहुयज्वा । बहुयज्वे–बहुयज्वानौ ।

४६२ । अन उपधालोपिनोऽन्यतरस्याम् । ४ । १ । २८ । अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप्स्यात् । पक्षे डाब्ङीब्निषेधौ । बहुराज्ञी । बहुराज्ञ्यौ–बहुराजे–बहुराजानौ ।

४६३ । प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः । ७ । ३ । ४४ । प्रत्ययस्थात्ककारात्पूर्वस्याकारस्येकारः स्यादापि परे स आप्सुपः परो न चेत् । सर्विका । कारिका । 'अतः' किम् । नौका । 'प्रत्ययस्थात्' किम् । शक्नोतीति शका । 'असुपः' किम् । बहुपरिव्राजका नगरी । 'कात्' किम् । नन्दना । 'पूर्वस्य' किम् । परस्य मा भूत् । कटुका । 'तपरः' किम् । राका । 'आपि' किम् । कारकः । 'मामकनरकयोरुपसंख्यानम्' (वा ४५२४) । मामिका । नरान्कायतीति नरिका । 'त्यक्त्यपोश्च' (वा ४५२५) । दाक्षिणात्यिका । इहत्यिका ।

४६४ । न यासयोः । ७ । ३ । ४५ । यत्तदोरस्येत्त्र स्यात् । यका । सका । यकाम् । सकाम् । 'त्यकनश्च निषेधः' (वा ४५२६) । अधित्यका । उपत्यका । 'आशिषि वुनश्च न' (वा ४५२८) । जीवका । भवका । 'उत्तरपदलोपे च' (वा ४५२९) । देवदत्तिका–देवका । 'क्षिपकादीनां च न' (वा ४५३०) । क्षिपका । ध्रुवका । कन्यका । चटका । 'तारका ज्योतिषि' (वा ४५३१) । अन्यत्र तारिका । 'वर्णका तान्तवे' (वा ४५३२) । अन्यत्र वर्णिका । 'वर्तका शकुनौ प्राचाम्' (वा ४५३३) । उदीचां तु वर्तिका । 'अष्टका पितृदैवत्ये' (वा ४५३४) । अष्टिकान्या । 'सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम्' (वा ४५३५) । इह वा अ इति छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतिका–सूतकेत्यादि ।

४६५ । उदीचामातः स्थाने यकपूर्वायाः । ७ । ३ । ४६ । यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । 'केऽणः' (सू ८३४) इति ह्रस्वः । आर्यका–आर्यिका । चटकका–चटकिका । 'आतः' किम् । सांकाश्ये भवा सांकाश्यिका । 'यक–' इति किम् । अश्विका । 'स्त्रीप्रत्यय–' इति किम् । शुभं यातीति । शुभंयाः ।

अज्ञाता शुभंयाः शुभंयिका। 'धात्वन्तयकोस्तु नित्यम्' (वा ४९३६)। सुनयिका
सुपाकिका।

४६६। भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि। ७। ३। ४७। स्वेत्यन्तं लुप्तषष्ठीकं पदम्
एषामत इद्वा स्यात्। तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम्। भस्त्राग्रहणमुपस
र्जनार्थम्। अन्यस्य तूत्तरसूत्रेण सिद्धम्। एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम्। अन्तर्वर्तिनं
विभक्तिमाश्रित्य 'असुपः' इति प्रतिषेधात्। अनेषका। परमैषका। अद्वके। परमद्वके
स्वशब्दग्रहणं संज्ञोपसर्जनार्थम्। इह हि 'आतः स्थाने' इत्यनुवृत्तं स्वशब्दस्यातो वि
स्वशब्दग्रहणं संज्ञोपसर्जनार्थम्। इह हि 'आतः स्थाने' इत्यनुवृत्तं स्वशब्दस्यातो वि-
षणम्। न तु द्वैषयोरसंभवात्। नाप्यन्येषामव्यभिचारात्। स्वशब्दस्त्वनुपसर्जनमात्मीय
वाची अकजर्हः। अर्थान्तरे तु न स्त्री। संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्युदाह
णम्। एवं चात्मीयायां स्विका। परमास्विकेति नित्यमेवेत्त्वम्। निर्भस्त्रका-निर्भस्त्रिका
एषका-एषिका। कृतषत्वनिर्देशान्नेह विकल्पः। एतिके-एतिकाः। अजका-अजिका
ज्ञका-ज्ञिका। द्विके-द्वके। निःस्वका-निःस्विका।

४६७। अभाषितपुंस्काच्च। ७। ३। ४८। एतस्माद्विहितस्यातः स्थानेऽत इ
स्यात्। गङ्गका-गङ्गिका। बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम्। अज्ञा
खट्वा अखट्विका। शैषिके कपि तु विकल्प एव।

४६८। आदाचार्याणाम्। ७। ३। ४९। पूर्वसूत्रविषय आद्वा स्यात्। गङ्गाका। उ
पुंस्कात्तु शुभ्रिका।

४६९। अनुपसर्जनात्। ४। १। १४। अधिकारोऽयम्। 'यूनस्तिः' (सू ९३१) इ
भिव्याप्य। अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति।

४७०। टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः। ४। १। १५। अ
पसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप्स्यात्। कुरुचरी। उपसर्ज
त्वान्नेह। बहुकुरुचरा। नदट्-नदी। वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप्प्राप्तः। यासुः
ङित्त्वेन 'लाश्रयमनुबन्धकार्यं नादेशानाम्' (प ७०) इति ज्ञापनान्न भवति। श्यः शानच्‌ःशित्त्वे
क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा। सौपर्णेयी। ऐन्द्री। औत्सी। ऊरु
यसी। ऊरुदघ्नी। ऊरुमात्री। पञ्चतयी। आक्षिकी। लावणिकी। यादृशी। इत्वरी
'ताच्छीलिके णेऽपि' (प ६८)। चौरी। 'नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम्'
(वा २४२५)। स्त्रैणी। पौंस्नी। शाक्तीकी। आढ्यंकरणी। तरुणी। तलुनी।

४७१। यञश्च। ४। १। १६। यञन्तात्स्त्रियां ङीप्स्यात्। अकारलोपे कृते।

४७२। हलस्तद्धितस्य। ६। ४। १५०। हल उत्तरस्य तद्धितयकारस्योपधाभूतस्
लोपः स्यादीति परे। गार्गी। 'अनपत्याधिकारस्थान्न ङीप्' (वा २४२६)। द्वीपे भवा द्वैप्या
अधिकारग्रहणान्नेह। देवस्यापत्यं दैव्या। 'देवाद्यञञौ' इति हि यञ्प्राग्दीव्यतीयो
त्वपत्याधिकारपठितः।

४७३। प्राचां ष्फ तद्धितः। ४। १। १७। यञन्तात्ष्फो वा स्यात्स्त्रियाम्,
च तद्धितः।

४७४। षः प्रत्ययस्य। १। ३। ६। प्रत्ययस्यादिः ष इत्स्यात्।

४७५। आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्। ७। १। २। प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः। तद्धितान्तत्वात्प्रातिपदिकत्वम्। षित्त्वसामर्थ्यात्ष्फेणोक्तेऽपि स्त्रीत्वे 'षिद्गौरा–' (सू ४९८) इति वक्ष्यमाणो ङीष्। गार्ग्यायणी।

४७६। सर्वत्र लोहितादिकतन्तेभ्यः। ४। १। १८। लोहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात्। लौहित्यायनी। कात्यायनी।

४७७। कौरव्यमाण्डूकाभ्यां च। ४। १। १९। आभ्यां ष्फः स्यात्। टाब्ङीपोरपवादः। 'कुर्वादिभ्यो ण्यः' (सू ११७९)। कौरव्यायणी। 'ढक्च मण्डूकात्' (सू ११२२) इत्यण्। माण्डूकायनी। 'आसुरेरुपसंख्यानम्' (वा २४३३) आसुरायणी।

४७८। वयसि प्रथमे। ४। १। २०। प्रथमवयोवाचिनोऽदन्तात्स्त्रियां ङीप्स्यात्। कुमारी। 'वयस्यचरम इति वाच्यम्' (वा २४३५)। वधूटी। चिरण्टी। वधूटचिरण्टशब्दौ यौवनवाचिनौ। 'अतः' किम्। शिशुः। 'कन्याया न'। 'कन्यायाः कनीन च' (सू ११११९) इति निर्देशात्।

४७९। द्विगोः। ४। १। २१। अदन्ताद्द्विगोर्ङीप्स्यात्। त्रिलोकी। अजादित्वात्त्रिफला। त्र्यनीका सेना।

४८०। अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि। ४। १। २२। अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीन्न स्यात्तद्धितलुकि सति। पञ्चभिरश्वैः क्रीता पञ्चाश्वा। आर्हीयष्ठक्। 'अध्यर्ध–' (सू १६९३) इति लुक्। द्वौ बिस्तौ पचति द्विबिस्ता। द्व्याचिता द्विकम्बल्या। परिमाणान्तात्तु द्व्याढकी। 'तद्धितलुकि' किम्। समाहारे पञ्चाश्वी।

४८१। काण्डान्तात्क्षेत्रे। ४। १। २३। क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि। द्वे काण्डे प्रमाणमस्या द्विकाण्डा क्षेत्रभक्तिः। 'प्रमाणे द्वयसज्–' (सू१८३८) इति विहितस्य मात्रचः 'प्रमाणे लो द्विगोर्नित्यम्' इति लुक्। 'क्षेत्रे' किम्। द्विकाण्डी रज्जुः।

४८२। पुरुषात्प्रमाणेऽन्यतरस्याम्। ४। १। २४। प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीब्वा स्यात्तद्धितलुकि। द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी–द्विपुरुषा वा परिखा।

४८३। ऊधसोऽनङ्। ५। ४। १३१। ऊधोऽन्तस्य बहुव्रीहेरनङादेशः स्यात्स्त्रियाम्। इत्यनङि कृते डाब्ङीब्निषेधेषु प्राप्तेषु।

४८४। बहुव्रीहेरूधसो ङीष्। ४। १। २५। ऊधोऽन्ताद्बहुव्रीहेर्ङीष् स्यात्स्त्रियाम्। कुण्डोध्नी। 'स्त्रियाम्' किम्। कुण्डोधो धेनुकम्। इहानङपि न। तद्विधौ 'स्त्रियाम्' (वा २३६७) इत्युपसंख्यानात्।

४८५। संख्याव्ययादेर्ङीप्। ४। १। २६। ङीषोऽपवादः। द्व्यूध्नी। अत्यूध्नी। बहुव्रीहेरित्येव। ऊधोऽतिक्रान्ता अत्यूधाः।

४८६। दामहायनान्ताच्च। ४। १। २७। संख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप्स्यात्। दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम्। द्विदाम्नी। अव्ययग्रहणाननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः। द्विहायनी बाला। 'त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम्' (वा ५०३८)। 'वयोवाचकस्यैव हायनस्य

ङीब्णत्वं चेष्यते' (वा २४४१)। त्रिहायणी। चतुर्हायणी। वयसोऽन्यत्र द्विहायना। त्रिहायना। चतुर्हायना शाला।

४८७। नित्यं संज्ञाछन्दसोः। ४। १। २९। अन्नन्ताद्बहुव्रीहेरुपधालोपिनो ङीप् स्यात्संज्ञाछन्दसोः। सुराज्ञी नाम नगरी। अन्यत्र पूर्वेण विकल्प एव। वेदे शतमूर्ध्नी।

४८८। केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च। ४। १। ३०। एभ्यो नवभ्यो नित्यं ङीप्स्यात्संज्ञाछन्दसोः। 'अथो त इन्द्रः केवलीर्विशः'। मामकी। भागधेयी। पापी। अपरी। समानी। आर्यकृती। सुमङ्गली। भेषजी। अन्यत्र केवला इत्यादि। मामकग्रहणं नियमार्थम्। अण्णन्तत्वादेव सिद्धेः। तेन लोकेऽसंज्ञायां मामिका।

४८९। अन्तर्वत्पतिवतोर्नुक्। ४। १। ३२। एतयोः स्त्रियां नुक्स्यात्। 'ऋन्नेभ्यो ङीप्' (सू २०६)। गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते। तत्रान्तरस्त्यस्मिन्गर्भ इति विग्रहेऽन्तःशब्दस्याधिकरणशक्तिप्रधानतयास्तिसामानाधिकरण्याभावादप्राप्तो मतुब्निपात्यते 'पतिवत्नी' इत्यत्र तु वत्त्वं निपात्यते। अन्तर्वत्नी। पतिवत्नी। प्रत्युदाहरणं तु। अन्तरस्त्यस्यां शालायां घटः। पतिमती पृथिवी।

४९०। पत्युर्नो यज्ञसंयोगे। ४। १। ३३। पतिशब्दस्य नकारादेशः स्याद्यज्ञेन संबन्धे। वसिष्ठस्य पत्नी। तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः। दंपत्योः सहाधिकारात्।

४९१। विभाषा सपूर्वस्य। ४। १। ३४। पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात्। गृहस्य पतिः गृहपतिः–गृहपत्नी। 'अनुपसर्जनस्य' इतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किं तु तदन्तस्य। तेन बहुव्रीहावपि। दृढपत्नी–दृढपतिः। वृषलपत्नी–वृषलपतिः। अथ 'वृषलस्य पत्नी' इति व्यस्ते कथमिति चेत्। पत्नीव पत्नीत्युपचारात्। यद्वा। आचारक्विबन्तात्कर्तरि क्विप्। आतिस्मश्च पक्षे। पात्नियौ। पत्निय इतीयङ्विषये विशेषः। 'सपूर्वस्य' किम्। गवां पतिः स्त्री।

४९२। नित्यं सपत्न्यादिषु। ४। १। ३५। पूर्वविकल्पापवादः। समानस्य सभावोऽपि निपात्यते। समानः पतिर्यस्याः सा सपत्नी। एकपत्नी। वीरपत्नी।

४९३। पूतक्रतोरै च। ४। १। ३६। अस्य स्त्रियामैआदेशो ङीप्च। 'इयं त्रिसूत्री पुंयोग एवेष्यते' (वा २४४९)। पूतक्रतोः स्त्री पूतक्रतायी। 'यया तु क्रतवः पूताः स्यात्तु पूतक्रतुरेव सा'।

४९४। वृषाकप्यग्निकुसितकुसिदानामुदात्तः। ४। १। ३७। एषामुदात्त ऐआदेशः स्यान्ङीप्च। वृषाकपेः स्त्री वृषाकपायी। 'हरिविष्णू वृषाकपी' इत्यमरः। 'वृषाकपायी श्रीगौर्योः' इति च। अग्नायी। कुसितायी। कुसिदायी। कुसिदशब्दो ह्रस्वमध्यो न दीर्घमध्यः।

४९५। मनोरौ वा। ४। १। ३८। मनुशब्दस्यौकारादेशः स्यादुदात्तैकारश्च वा। तात्सांनियोगशिष्टो ङीप् च। मनोः स्त्री मनायी–मनावी–मनुः।

४९६। वर्णादनुदात्तात्तोपधात्तो नः। ४। १। ३९। वर्णवाची योऽनुदात्तान्तस्तोप

धस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप्स्यात् तकारस्य नकारादेशश्च । एनी एता । रोहिणी–रोहिता । 'वर्णानां तणतिनितान्तानाम्' (फि ३३) इति फिट्सूत्रेणाद्युदात्तः । 'त्र्येण्या च शलल्या' इति गृह्यम् । त्रीण्येतान्यस्या इति बहुव्रीहिः । 'अनुदात्तात्' किम् । श्वेता । 'घृतादीनां च' (फि २१) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । 'पिशङ्गादुपसंख्यानम्' (वा २४५५) । पिशङ्गी–पिशङ्गा । 'असितपलितयोर्न' (वा २४५३) । असिता । पलिता । 'छन्दसि क्नमेके' (वा २४५४) । असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची । किं तु विशुद्धिवाची । तेन अवदाता इत्येव ।

४९७ । अन्यतो ङीष् । ४ । १ । ४० । तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात्स्त्रियां ङीष्स्यात् । कल्माषी । सारङ्गी । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' (फि ४२) इति मध्योदात्तावेतौ । 'अनुदात्तान्तात्' किम् । कृष्णा । कपिला ।

४९८ । षिद्गौरादिभ्यश्च । ४ । १ । ४१ । षिद्भ्यो गौरादिभ्यश्च ङीष्स्यात् । नर्तकी । गौरी । 'आमनडुहः स्त्रियां वा'(वा ४३७८) । अनडुही–अनड्वाही । 'पिप्पल्यादयश्च' (ग ४७) । आकृतिगणोऽयम् ।

४९९ । सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः । ६ । ४ । १४९ । अङ्गस्योपधाया यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः । 'मत्स्यस्य ङ्याम्' (४१९८) । 'सूर्यागस्त्ययोश्छे च ङ्यां च' (वा ४१९९) । 'तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्' (वा ४२००) । मत्सी । 'मातरि षिच्च' (वा २७१०) इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष् । दंष्ट्रा ।

५०० । जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु । ४ । १ । ४२ । एकादशभ्यः प्रातिपदिकेभ्यः क्रमाद्वृत्त्यादिष्वर्थेषु ङीष्स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदी । उत्सादित्वादञन्तत्वेन 'टिड्ढ–' (सू ४७०) इति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् । कुण्डान्या । 'कुडि दाहे' । 'गुरोश्च हलः' (सू ३२८०) इत्यप्रत्ययः । यस्तु 'अमृते जारजः कुण्डः' इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो ङीष् विधीयते न तु नियम्यते । गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलान्या । भाजी श्राणा चेत् । भाजान्या । नागी स्थूला चेत् । नागान्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालान्या । नीली अनाच्छादनं चेत् । नीलान्या । नील्या रक्ता शाटीत्यर्थः । 'नील्या अन्वक्तव्यः' (वा २६८०) इत्यन् । अनाच्छादनेऽपि न सर्वत्र । किं तु 'नीलादोषधौ' (वा २४५६) । नीली । 'प्राणिनि च' (वा २४५७) । नीली गौः । 'संज्ञायां वा' (वा २४५८) । नीली–नीला । कुशी अयोविकारश्चेत् । कुशान्या । कामुकी मैथुनेच्छा चेत् । कामुकान्या । कबरी केशानां संनिवेशश्चेत् । कबरान्या । चित्रेत्यर्थः ।

५०१ । शोणात्प्राचाम् । ४ । १ । ४३ । शोणी–शोणा ।

५०२ । वोतो गुणवचनात् । ४ । १ । ४४ । उदन्ताद्गुणवाचिनो वा ङीष्स्यात् ।

मृद्वी–मृदुः । 'उतः' किम् । शुचिः । 'गुण–' इति किम् । आखुः । 'खरुसंयोगोपधान्न' (वा २४६०) । 'खरुः पतिंवरा कन्या' । पाण्डुः ।

५०३ । बह्वादिभ्यश्च । ४ । १ । ४५ । एभ्यो वा ङीष्स्यात् । बह्वी–बहुः । 'कृदिकारादक्तिनः' (ग ५०) । रात्रिः–रात्री । 'सर्वतोऽक्तिन्नर्थादित्येके' (ग ५१) । शकटिः–शकटी । 'अक्तिन्नर्थात्' किम् । अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थं पद्धतिशब्दो गणे पठ्यते । 'हिमकाषिहतिषु च' (सू ९९२) इति पद्भावः । पद्धतिः–पद्धती ।

५०४ । पुंयोगादाख्यायाम् । ४ । १ । ४८ । या पुमाख्या पुंयोगात्स्त्रियां वर्तते ततो ङीष्स्यात् । गोपस्य स्त्री गोपी । 'पालकान्तान्न (वा २४६९) । गोपालिका । अश्वपालिका । 'सूर्याद्देवतायां चाब्वाच्यः' (वा २४७१) । सूर्यस्य स्त्री देवता सूर्या । 'देवतायाम्' किम् सूरी कुन्ती मानुषीयम् ।

५०५ । इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् । ४ । १ । ४९ । एषामानुगागमः स्यान्ङीष्च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी । 'हिमारण्ययोर्महत्त्वे' (वा २४७२) । महद्धिमं हिमानी । अरण्यानी । 'यवाद्दोषे' (वा २४७३) दुष्टो यवो यवानी । 'यवनाल्लिप्याम्' (वा २४७४) । मातुलानी–मातुली । उपाध्यायानी–उपाध्यायी । या तु स्वयमेवाध्यापिका तत्र वा ङीप् वाच्यः । उपाध्यायी–उपाध्याया । 'आचार्यादणत्वं च' (वा २४७७) । आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री । 'अर्यक्षत्रियाभ्यां वा स्वार्थे' (वा २४७८) । अर्याणी । अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी । क्षत्रियी । कथं 'ब्रह्माणी' इति । ब्रह्माणमानयति जीवयतीति । 'कर्मण्यण्' (सू २९१३) ।

५०६ । क्रीतात्करणपूर्वात् । ४ । १ । ५० । क्रीतान्तादन्तात्करणादेः स्त्रियां ङीष्स्यात् 'वस्त्रक्रीती । 'क्वचिन्न' । धनक्रीता ।

५०७ । क्तादल्पाख्यायाम् । ४ । १ । ५१ । करणादेः क्तान्तात्स्त्रियां ङीष्स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः । 'अल्पाख्यायाम्' किम् । चन्दनलिप्ताङ्गना ।

५०८ । बहुव्रीहेश्चान्तोदात्तात् । ४ । १ । ५२ । बहुव्रीहेः क्तान्तादन्तोदात्तादन्तात्स्त्रियां ङीष्स्यात् । 'जातिपूर्वादिति वक्तव्यम्' (वा २४८४) । तेन 'बहुनञ्सुकालसुखादिपूर्वान्न' । ऊरुभिन्नी । नेह । बहुकृता । 'जातान्तान्न' (वा २४७९) । दन्तजाता । 'पाणिगृहीती भार्यायाम्' (वा २४८०) । पाणिगृहीतान्या ।

५०९ । अस्वाङ्गपूर्वपदाद्वा । ४ । १ । ५३ । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती–सुरापीता । 'अन्तोदात्तात्' किम् । वस्त्रच्छन्ना । 'अनाच्छादनात्' इत्युदात्तनिषेधः अत एव पूर्वेणापि न ङीष् ।

५१० । स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । ४ । १ । ५४ । असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्तादन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी–अतिकेशा । चन्द्रमुखी–चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । 'उपसर्जनात्' किम् । शिखा । स्वाङ्गं त्रिधा ।

१. २१८४ वार्तिकेनेति भावः ।

'अद्रवन्मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम्।
सुस्वेदा। द्रवत्वात्। सुज्ञाना। अमूर्तत्वात्। सुमुखा शाला। अप्राणिस्थत्वात्। सुशोफा विकारजत्वात्।
'अतत्स्थं तत्र दृष्टं च—
सुकेशी सुकेशा वा रथ्या। अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात्।
—तेन चेत्तत्तथायुतम्'॥
सुस्तनी-सुस्तना वा प्रतिमा। प्राणिवत्प्राणिसदृशे स्थितत्वात्।

५११। नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च। ४। १। ५५। एभ्यो वा ङीष्स्यात्। आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते पुरस्तादपवादन्यायात्। ओष्ठादीनां पञ्चानां तु 'असंयोगोपधात्' इति पर्युदासे प्राप्ते वचनं मध्येऽपवादन्यायात्। सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः। तुङ्गनासिकी-तुङ्गनासिकेत्यादि। नेह। सहनासिका। अनासिका अत्र वृत्तिः। 'अङ्गगात्रकण्ठेभ्यो वक्तव्यम्'। स्वङ्गी-स्वङ्गेत्यादि। एतच्चानुक्तसमुच्चयार्थेन चकारेण संग्राह्यमिति केचित्। 'भाष्याद्यनुक्तत्वादप्रमाणम्' इति प्रामाणिकाः। अत्र वार्तिकानि। 'पुच्छाच्च' (वा २४८९)। सुपुच्छी-सुपुच्छा। 'कबरमणिविषशरेभ्यो नित्यम्' (वा २४९०)। कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरीत्यादि। 'उपमानात्पक्षाच्च पुच्छाच्च' (वा २४९१)। नित्यमित्येव। उलूकपक्षी शाला। उलूकपुच्छी सेना।

५१२। न क्रोडादिबह्वचः। ४। १। ५६। क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष्। कल्याणक्रोडा। अश्वानामुरः क्रोडा। आकृतिगणोऽयम्। सुजघना।

५१३। सहनञ्विद्यमानपूर्वाच्च। ४। १। ५७। सहेत्यादित्रिकपूर्वान्न ङीष्। सकेशा। अकेशा। विद्यमाननासिका।

५१४। नखमुखात्संज्ञायाम्। ४। १। ५८। ङीष्न स्यात्। शूर्पणखा। गौरमुखा। 'संज्ञायाम्' किम्। ताम्रमुखी कन्या।

५१५। दिक्पूर्वपदान्ङीप्। ४। १। ६०। दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात्। प्राङ्मुखी। आद्युदात्तं पदम्।

५१६। वाहः। ४। १। ६१। वाहन्तात्प्रातिपदिकान्ङीष्स्यात्। ङीषेवानुवर्तते न ङीप्। 'दित्यवाट् च मे दित्यौही च मे'।

५१७। सख्यशिश्वीति भाषायाम्। ४। १। ६२। इतिशब्दः प्रकारे 'भाषायाम्' इत्यस्यानन्तरं द्रष्टव्यः। छन्दस्यपि क्वचित्। सखी। अशिश्वी। 'आधेनवो धुनयन्तामशिश्वीः'।

५१८। जातेरस्त्रीविषयादयोपधात्। ४। १। ६३। जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष्स्यात्।
'आकृतिग्रहणा जातिः—
अनुगतसंस्थानव्यङ्ग्येत्यर्थः। तटी।
—लिङ्गानां च न सर्वभाक्।

१—९ भाष्योक्तमिदम्।

सकृदाख्यातनिर्ग्राह्या–

'असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिः' इति।
लक्षणान्तरम्। वृषली। 'सत्यन्तम्' किम्। शुक्ला। 'सकृत्–' इत्यादि किम्। देवदत्ता।

–गोत्रं च चरणैः सह ॥'

अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः। औपगवी। कठी।
बह्वृची। ब्राह्मणीत्यत्र तु शार्ङ्गरवादिपाठान्ङीना ङीष्बाध्यते। 'जातेः' किम्। मुण्डा।
'अस्त्रीविषयात्' किम्। बलाका। 'अयोपधात्' किम्। क्षत्रिया। योपधप्रतिषेधे 'हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः' (वा २४९९)। हयी। गवयी। मुकयी। 'हलस्तद्धितस्य' (सू ४७२) इति लोपः। मानुषी। 'मत्स्यस्य ङ्याम्' (वा ४१९८)। मत्सी।

५१९। पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च। ४। १। ६४। पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष्स्यात्। ओदनपाकी। शङ्कुकर्णी। शालपर्णी। शङ्खपुष्पी। दासीफली। दर्भमूली। गोवाली। ओषधिविशेषे रूढा एते।

५२०। इतो मनुष्यजातेः। ४। १। ६५। ङीष्स्यात्। दाक्षी। योपधादपि। उदमेः स्यापत्यम् औदमेयी। 'मनुष्य–' इति किम्। तित्तिरिः।

५२१। ऊङुतः। ४। १। ६६। उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात्। कुरूः। 'कुरुनादिभ्यो ण्यः' (सू ११९०)। तस्य 'स्त्रियामवन्ति–' (सू ११९५) इत्यादिना लुक्। 'अयोपधात्' किम्। अध्वर्युः। 'अप्राणिजातेश्चारज्ज्वादीनामुपसंख्यानम्' (वा २५०२)। रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव। अलाबूः। कर्कन्धूः। अनयोर्दीर्घान्तत्वेऽपि 'नोङ्धात्वोः' (सू ३७२१) इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम्। प्राणिजातेस्तु कृकवाकुः। रज्ज्वादेस्तु रज्जुः। हनुः।

५२२। बाह्वन्तात्संज्ञायाम्। ४। १। ६७। स्त्रियामूङ् स्यात्। भद्रबाहूः। 'संज्ञायाम्' किम्। वृत्तबाहुः।

५२३। पङ्गोश्च। ४। १। ६८। पङ्गूः। 'श्वशुरस्योकाराकारलोपश्च (वा ५०३९)।[1] चादूङ्। पुंयोगलक्षणस्य ङीषोऽपवादः। लिङ्गविशिष्टपरिभाषया स्वादयः। श्वश्रूः।

५२४। ऊरूत्तरपदादौपम्ये। ४। १। ६९। उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात्। करभोरूः।

५२५। संहितशफलक्षणवामादेश्च। ४। १। ७०। अनौपम्यार्थं सूत्रम्। संहितोरूः। सैव शफोरूः। शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात्। लक्षणशब्दादर्शआद्यच्। लक्षणोरूः। वामोरूः। 'सहितसहाभ्यां चेति वक्तव्यम्' (वा २५०३)। हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः। सहेते इति सहौ ऊरू यस्याः सा सहोरूः। यद्वा। विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः।

---

१. इदं च 'श्वशुरः श्वश्र्वा' (१।२।७१) इति निर्देशसिद्धमिति भावः। 'ङ्याप्–' (४।१।१) इति सूत्रस्थस्य 'उवर्णान्तादूङ् विधीयते। तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति' इति भाष्यस्य स्वरसस्तु 'जम्ब्वादित्वान्निष्पन्नादूङ् दीर्घोकारान्त एव वा कर्तव्यः' इत्येव लभ्यते।

५२६। संज्ञायाम्। ४। १। ७२। कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात्। कद्रूः। कमण्डलूः। 'संज्ञायाम्' किम्। कद्रुः। कमण्डलुः। अच्छन्दोऽर्थं वचनम्।

५२७। शार्ङ्गरवाद्यञो ङीन्। ४। १। ७३। शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन्स्यात्। शार्ङ्गरवी। वैदी। 'जातेः' इत्यनुवृत्तेः पुंयोगे ङीषेव 'नृनरयोर्वृद्धिश्च' (ग ९४) इति गणसूत्रम्। नारी।

५२८। यङश्चाप्। ४। १। ७४। यङन्तात्स्त्रियां चाप्स्यात्। ष्यङ्ष्यङोः सामान्यग्रहणम्। आम्बष्ठ्या। कारीषगन्ध्या। 'षाच्यञश्चाब्वाच्यः' (वा २५०५)। पौतिमाष्या।

५२९। आवट्याच्च। ४। १। ७५। अस्माच्चाप्स्यात्। 'यञश्च' (सू ४७१) इति ङीपोऽपवादः। अवटशब्दो गर्गादिः। आवट्या।

५३०। तद्धिताः। ४। १। ७६। आ पञ्चमसमाप्तेरधिकारोऽयम्।

५३१। यूनस्तिः। ४। १। ७७। युवन्शब्दात्तिप्रत्ययः स्यात्। स च तद्धितः। लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः। युवतिः। अनुपसर्जनादित्येव। बहवो युवानो यस्यां सा बहुयुवा। युवतीति तु यौतेः शत्रन्तान्ङीपि बोध्यम्।

इति स्त्रीप्रत्ययप्रकरणम्।

अथ कारकादिविभक्तिप्रकरणम्।

५३२। प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा। २। ३। ४६। नियतोपस्थितिकः प्रातिपदिकार्थः। मात्रशब्दस्य प्रत्येकं योगः। प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये संख्यामात्रे च प्रथमा स्यात्। उच्चैः। नीचैः। कृष्णः। श्रीः। ज्ञानम्। अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम्। अनियतलिङ्गास्तु लिङ्गमात्राद्याधिक्यस्य। तटः—तटी—तटम्। परिमाणमात्रे द्रोणो व्रीहिः। द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः। प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम्, प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः। वचनं संख्या। एकः। द्वौ। बहवः। इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम्।

५३३। संबोधने च। २। ३। ४७। इह प्रथमा स्यात्। हे राम।

इति प्रथमा।

५३४। कारके। १। ४। २३। इत्यधिकृत्य।

५३५। कर्तुरीप्सिततमं कर्म। १। ४। ४९। कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात्। 'कर्तुः' किम्। माषेष्वश्वं बध्नाति। कर्मण ईप्सिता माषाः, न तु कर्तुः। तमब्ग्रहणं किम्। पयसा ओदनं भुङ्क्ते। 'कर्म' इत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम्। अन्यथा गेहं प्रविशतीत्यत्रैव स्यात्।

५३६। अनभिहिते। २। ३। १। इत्यधिकृत्य।

५३७। कर्मणि द्वितीया। २। ३। २। अनुक्ते कर्मणि द्वितीया स्यात्। हरिं भजति। अभिहिते तु कर्मणि 'प्रातिपदिकार्थमात्रे' इति प्रथमैव। अभिधानं तु प्रायेण तिङ्कृत्तद्धितसमासैः। तिङ्। हरिः सेव्यते। कृत्। लक्ष्म्या सेवितः। तद्धितः। शतेन क्रीतः शत्यः।

समासः । प्राप्त आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानम् । यथा । 'विषवृक्षोऽ संवर्ध्य स्वयं छेत्तुमसांप्रतम्' । सांप्रतमित्यस्य हि युज्यत इत्यर्थः ।

५३८ । तथायुक्तं चानीप्सितम् । १ । ४ । ५० । ईप्सिततमवत्क्रियया युक्तम ीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छंस्तृणं स्पृशति । ओदनं भुञ्जानो विषं भु

५३९ । अकथितं च । १ । ४ । ५१ । अपादानादिविशेषैरविवक्षितं कारकं क सञ्ज्ञं स्यात् ।

दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्[1] ।
कर्मयुक्स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥

'दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्म' परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् । अविनीतं वि याचते । तण्डुलानोदनं पचति । गर्गाञ्छतं दण्डयति । व्रजमवरुणद्धि गाम् । मा वकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते–शास्ति वा । श जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नय हरति–कर्षति–वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं भाषते–अभिधत्ते–वक्तीत्यादि । 'कारकम्' किम् । माणवकस्य पितरं पन्थानं पृच्छ 'अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्य (वा ११०३–११०४) । कुरून्स्वापयति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ।

५४० । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ । १ । ४ । ५२ । गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ।

शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् ।
आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ।
आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥

'गति–' इत्यादि किम् । पाचयत्योदनं देवदत्तेन । 'अण्यन्तानाम्' किम् । गमयति देवद यज्ञदत्तं तमपरः प्रयुङ्क्ते । गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः । 'नीवह्योर्न' (वा ११० नाययति वाहयति वा भारं भृत्येन । 'नियन्तृकर्तृकस्य वहेरनिषेधः' (वा १११०) । वाहय रथं वाहान्सूतः । 'आदिखाद्योर्न' (वा ११०९) । आदयति खादयति वान्नं बटुना । 'भक्षेरहिं र्थस्य न' (वा ११११) । भक्षयत्यन्नं बटुना । 'अहिंसार्थस्य' किम् । भक्षयति बलीवर्दान् स्यम् । 'जल्पतिप्रभृतीनामुपसंख्यानम्' (वा ११०७) । जल्पयति भाषयति वा धर्मं पु देवदत्तः । 'दृशेश्च' (वा ११०८) । दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानाम ग्रहणं न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन 'स्मरति' 'जिघ्रति' इत्यादीनां न । स्मार यति घ्रापयति देवदत्तेन । 'शब्दायतेर्न' (वा ११०५) । शब्दाययति देवदत्तेन । धात्व संगृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः न त्वविवक्षितकर्माणोऽपि । तेन 'मासमासयति देवदत्तम्' इत्यादौ कर्मत्वं भवति । 'दे दत्तेन पाचयति' इत्यादौ तु न ।

---

१ इदं च १०९०, ११०० वार्तिकादिसिद्धम् ।

५४१। हृक्रोरन्यतरस्याम्। १। ४। ५३। हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात्। हारयति कारयति वा भृत्यं-भृत्येन वा कटम्। 'अभिवादिदृशोरात्मनेपदे वेति वाच्यम्' (वा ११२४)। अभिवादयते दर्शयते देवं भक्तं-भक्तेन वा।

५४२। अधिशीङ्स्थासां कर्म। १। ४। ४६ अधिपूर्वाणामेषामाधारः कर्म स्यात्। अधिशेते-अधितिष्ठति-अध्यास्ते वा वैकुण्ठं हरिः।

५४३। अभिनिविशश्च। १। ४। ४७। अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात्। अभिनिविशते सन्मार्गम्। 'परिक्रयणे संप्रदानम्-' (सू ५८०) इति सूत्रादिह मण्डूकप्लुत्यान्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न। पापेऽभिनिवेशः।

५४४। उपान्वध्याङ्वसः। १। ४। ४८। उपादिपूर्वस्य वसतेराधारः कर्म स्यात्। उपवसति-अनुवसति-अधिवसति-आवसति वा वैकुण्ठं हरिः। 'अभुक्त्यर्थस्य न' (वा १०८७)। वने उपवसति।

'उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते॥' (वा १४४४)

उभयतः कृष्णं गोपाः। सर्वतः कृष्णम्। धिक् कृष्णाभक्तम्। उपर्युपरि लोकं हरिः। अध्यधि लोकम्। अधोऽधो लोकम्। 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' (वा १४४२-१४४३)। अभितः कृष्णम्। परितः कृष्णम्। ग्रामं समया। निकषा लङ्काम्। हा कृष्णाभक्तम्। तस्य शोच्यत इत्यर्थः। 'बुभुक्षितं न प्रतिभाति किंचित्'।

५४५। अन्तरान्तरेणयुक्ते। २। ३। ४। आभ्यां योगे द्वितीया स्यात्। अन्तरा त्वां मां हरिः। अन्तरेण हरिं न सुखम्।

५४६। कर्मप्रवचनीयाः। १। ४। ८३। इत्यधिकृत्य।

५४७। अनुर्लक्षणे। १। ४। ८४। लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात्। गत्युपसर्गसंज्ञापवादः।

५४८। कर्मप्रवचनीययुक्ते द्वितीया। २। ३। ८। एतेन योगे द्वितीया स्यात्। जपमनु प्रावर्षत्। हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः। परापि हेतौ तृतीयानेन बाध्यते। 'लक्षणेत्थंभूत-' (सू ५५२) इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात्।

५४९। तृतीयार्थे। १। ४। ८५। अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात्। नदीमन्ववसिता सेना। नद्या सह संबद्धेत्यर्थः। 'षिञ् बन्धने' क्तः।

५५०। हीने। १। ४। ८६। हीने द्योत्येऽनुः प्राग्वत्। अनु हरिं सुराः। हरेर्हीना इत्यर्थः।

५५१। उपोऽधिके च। १। ४। ८७। अधिके हीने च द्योत्य उपेत्यव्ययं प्राक्संज्ञं स्यात्। अधिके सप्तमी वक्ष्यते। हीने उप हरिं सुराः।

५५२। लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः। १। ४। ९०। एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः। लक्षणे। वृक्षं प्रति-परि-अनु वा विद्योतते विद्युत्। इत्थंभूताख्याने। भक्तो विष्णुं प्रति-परि-अनु वा। भागे। लक्ष्मीर्हरिं प्रति-परि-अनु वा।

हरेर्भाग इत्यर्थः । वीप्सायाम् । वृक्षं वृक्षं प्रति-परि-अनु वा सिञ्चति । अत्रोपसर्गत्वाभा
षत्वम् । 'एषु' किम् । परिषिञ्चति ।

५५३ । अभिरभागे । १ । ४ । ९१ । भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । हरि
भिवर्तते । भक्तो हरिमभि । देवं देवमभिसिञ्चति । 'अभागे' किम् । यदत्र ममाभि
न्दीयताम् ।

५५४ । अधिपरी अनर्थकौ । १ । ४ । ९३ । उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छ
कुतः पर्यागच्छति । गतिसंज्ञाबाधात् 'गतिर्गतौ' (सू ३९७७) इति निघातो न ।

५५५ । सुः पूजायाम् । १ । ४ । ९४ । सु सिक्तम् । सु स्तुतम् । अनुपसर्गत्वान्न ष
'पूजायाम्' किम् । सुषिक्तं किं तवात्र । आक्षेपोऽयम् ।

५५६ । अतिरतिक्रमणे च । १ । ४ । ९५ । अतिक्रमणे पूजायां चातिः कर्मप्र
नीयसंज्ञः स्यात् । अति देवान्कृष्णः ।

५५७ । अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु । १ । ४ । ९६ । एषु द्यो
त्वपिरुक्तसंज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । त
एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संब
'सर्पिषः' इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसंबन्धे । इ
वापिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते सर्पिषो बिन्दुना योगो न त
नेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । अपि स्तु
अन्ववसर्गः कामचारानुज्ञा । धिग्देवदत्तमपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च अ
स्तुहि । समुच्चये ।

५५८ । कालाध्वनोरत्यन्तसंयोगे । २ । ३ । ५ । इह द्वितीया स्यात् । मासं कल्याण
मासमधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । 'अत्य
संयोगे' किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ।

इति द्वितीया ।

५५९ । स्वतन्त्रः कर्ता । १ । ४ । ५४ । क्रियायां स्वातन्त्र्येण विवक्षितोऽ
कर्ता स्यात् ।

५६० । साधकतमं करणम् । १ । ४ । ४२ । क्रियासिद्धौ प्रकृष्टोपकारकं कारकं क
णसंज्ञं स्यात् । तमब्ग्रहणं किम् । गङ्गायां घोषः ।

५६१ । कर्तृकरणयोस्तृतीया । २ । ३ । १८ । अनभिहिते कर्तरि करणे च तृती
स्यात् । रामेण बाणेन हतो वाली । 'प्रकृत्यादिभ्य उपसंख्यानम्' (वा १४६६) । प्रकृ
चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणा
सुखेन दुःखेन वा यातीत्यादि ।

५६२ । दिवः कर्म च । १ । ४ । ४३ । दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्कर
संज्ञम् । अक्षैरक्षान्वा दीव्यति ।

५६३ । अपवर्गे तृतीया । २ । ३ । ६ । अपवर्गः फलप्राप्तिः, तस्यां द्योत्यायां का

ध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वानुवाकोऽधीतः । 'अपवर्गे' किम्। मासमधीतो नायातः।

९६४। सहयुक्तेऽप्रधाने। २। ३। १९ । सहार्थेन युक्तेऽप्रधाने तृतीया स्यात्। पुत्रेण सहागतः पिता। एवं साकंसार्धंसमंयोगेऽपि। विनापि तद्योगं तृतीया । 'वृद्धो यूना—' (सू ९३१) इत्यादिनिर्देशात्।

९६५। येनाङ्गविकारः। २। ३। २०। येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते तत-स्तृतीया स्यात्। अक्ष्णा काणः। अक्षिसंबन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम्। अक्षि काणमस्य ।

९६६। इत्थंभूतलक्षणे। २। ३। २१ । कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात्। जटाभिस्तापसः। जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः।

९६७। संज्ञोऽन्यतरस्यां कर्मणि। २। ३। २२। संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात्। पित्रा पितरं वा संजानीते।

९६८। हेतौ। २। ३। २३। हेत्वर्थे तृतीया स्यात्। द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम्। करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः। पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । 'गम्यमानापि क्रिया कारकविभक्तौ प्रयो-जिका'। अलं श्रमेण। श्रमेण साध्यं नास्तीत्यर्थः । इह साधनक्रियां प्रति श्रमः करणम्। शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः । 'अशिष्टव्यवहारे[1] दाणः प्रयोगे चतुर्थ्यर्थे तृतीया' (वा ५०४०) । दास्या संयच्छते कामुकः । धर्मे तु भार्यायै संयच्छति।

इति तृतीया।

९६९। कर्मणा यमभिप्रैति स संप्रदानम्। १। ४। ३२ । दानस्य कर्मणा यमभि-प्रैति स संप्रदानसंज्ञः स्यात्।

९७०। चतुर्थी संप्रदाने। २। ३। १३ । विप्राय गां ददाति । अनभिहित इत्येव। दीयतेऽस्मै दानीयो विप्रः। 'क्रियया यमभिप्रैति सोऽपि संप्रदानम्' (वा १०८५)। पत्ये शेते। 'कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा' (वा १०८६) । पशुना रुद्रं यजते। पशुं रुद्राय ददातीत्यर्थः।

९७१। रुच्यर्थानां प्रीयमाणः। १। ४। ३३। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः संप्रदानं स्यात्। हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कर्त्री। 'प्रीयमाणः' किम्। देवदत्ताय रोचते मोदकः पथि।

९७२। श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः । १। ४। ३४। एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा। 'ज्ञीप्स्यमानः' किम्। देवदत्ताय श्लाघते पथि।

---

१ इदं च 'दाणश्च सा चेच्चतुर्थ्यर्थे' (१। ३। ५४) इति सूत्रज्ञापितम् । तत्र 'अशिष्ट-व्यवहारे' इत्यंशो भाष्यकृतो वाचनिकः।

५७३ । धारेरुत्तमर्णः । १ । ४ । ३५ । धारयतेः प्रयोग उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । 'उत्तमर्णः' किम् । देवदत्ताय शतं धारयति ग्रामे ।

५७४ । स्पृहेरीप्सितः । १ । ४ । ३६ । स्पृहयतेः प्रयोग इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । 'ईप्सितः' किम् । पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्र इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ।

५७५ । क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः । १ । ४ । ३७ । क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति द्रुह्यति ईर्ष्यति असूयति । 'यं प्रति कोपः' किम् । भार्यामीर्ष्यति । मैनामन्यो द्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते अतो विशेषणं सामान्येन 'यं प्रति कोपः' इति ।

५७६ । क्रुधद्रुहोरुपसृष्टयोः कर्म । १ । ४ । ३८ । सोपसर्गयोरनयोर्योगे यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति-अभिद्रुह्यति ।

५७७ । राधीक्ष्योर्यस्य विप्रश्नः । १ । ४ । ३९ । एतयोः कारकं संप्रदानं स्यात्, यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति-ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ।

५७८ । प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता । १ । ४ । ४० । आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति-आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितस्तत्प्रतिजानीत इत्यर्थः ।

५७९ । अनुप्रतिगृणश्च । १ । ४ । ४१ । आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति-प्रतिगृणाति । होता प्रथमं शंसति, तमध्वर्युः प्रोत्साहयतीत्यर्थः ।

५८० । परिक्रयणे संप्रदानमन्यतरस्याम् । १ । ४ । ४४ । नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन्साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन-शताय वा परिक्रीतः । 'तादर्थ्ये चतुर्थी वाच्या' (वा १४५८) । मुक्तये हरिं भजति । 'क्लृपि संपद्यमाने च' (वा १४५९) । भक्तिर्ज्ञानाय कल्पते-संपद्यते-जायत इत्यादि । 'उत्पातेन ज्ञापिते च' (वा १४६०) । वाताय कपिला विद्युत् । 'हितयोगे च' (वा १४६१) । ब्राह्मणाय हितम् ।

५८१ । क्रियार्थोपपदस्य च कर्मणि स्थानिनः । २ । ३ । १४ । क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं 'स्वयंभुवे नमस्कृत्य' इत्यादावपि ।

५८२ । तुमर्थाच्च भाववचनात् । २ । ३ । १५ । 'भाववचनाश्च' (सू ३१८०) इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ।

५८३ । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । २ । ३ । १६ । एभिर्योगे चतुर्थी स्यात् । हरये नमः । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' (प १०३) । नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन

दैत्येभ्यो हरिरलं-प्रभुः-समर्थः-शक्त इत्यादि। प्रभ्वादियोगे षष्ठ्यपि साधुः। 'तस्मै प्रभवति-' (सू १७६९), 'स एषां ग्रामणीः' (सू १८७८) इति निर्देशात्। तेन 'प्रभुर्बुभूषुर्भुवनत्रयस्य' इति सिद्धम्। वषडिन्द्राय। चकारः पुनर्विधानार्थः। तेनाशीर्विवक्षायां परामपि 'चतुर्थी चाशिषि-' (सू ६३१) इति षष्ठीं बाधित्वा चतुर्थ्येव भवति। स्वस्ति गोभ्यो भूयात्।

५८४। मन्यकर्मण्यनादरे विभाषाप्राणिषु। २। ३। १७। प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे। न त्वां तृणं मन्ये तृणाय वा। श्यना निर्देशात्तानादिकयोगे न। न त्वां तृणं मन्वे। 'अप्राणिष्वित्यपनीय नौकाकान्नशुकशृगालवर्जेष्विति वाच्यम्' (वा १४६४)। तेन न त्वां नावमन्नं मन्य इत्यत्राप्राणित्वेऽपि चतुर्थी न। न त्वां शुने मन्य इत्यत्र प्राणित्वेऽपि भवत्येव।

५८५। गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि। २। ३। १२। अध्वभिन्ने गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम्। ग्रामं ग्रामाय वा गच्छति। 'चेष्टायाम्' किम्। मनसा हरिं व्रजति। 'अनध्वनि' इति किम्। पन्थानं गच्छति। गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः। यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव। उत्पथेन पथे गच्छति।

इति चतुर्थी।

५८६। ध्रुवमपायेऽपादानम्। १। ४। २४। अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात्।

५८७। अपादाने पञ्चमी। २। ३। २८। ग्रामादायाति। धावतोऽश्वात्पतति। 'कारकम्' किम्। वृक्षस्य पर्णं पतति। 'जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' (वा १०७९)। पापाज्जुगुप्सते विरमति। धर्मात्प्रमाद्यति।

५८८। भीत्रार्थानां भयहेतुः। १। ४। २५। भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुरपादानं स्यात्। चोराद्बिभेति। चोरात्त्रायते। 'भयहेतुः' किम्। अरण्ये बिभेति त्रायते वा।

५८९। पराजेरसोढः। १। ४। २६। पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात्। अध्ययनात्पराजयते। ग्लायतीत्यर्थः। 'असोढः' किम्। शत्रून्पराजयते। अभिभवतीत्यर्थः।

५९०। वारणार्थानामीप्सितः। १। ४। २७। प्रवृत्तिविघातो वारणम्, वारणार्थानां धातूनां प्रयोगे ईप्सितोऽर्थोऽपादानं स्यात्। यवेभ्यो गां वारयति। 'ईप्सितः' किम्। यवेभ्यो गां वारयति क्षेत्रे।

५९१। अन्तर्धौ येनादर्शनमिच्छति। १। ४। २८। व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात्। मातुर्निलीयते कृष्णः। 'अन्तर्धौ' किम्। चौरान्न दिदृक्षते। 'इच्छति'ग्रहणं किम्। अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्। देवदत्ताद्यज्ञदत्तो निलीयते।

५९२ । आख्यातोपयोगे । १ । ४ । २९ । नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । 'उपयोगे' किम् । नटस्य गाथां शृणोति ।

५९३ । जनिकर्तुः प्रकृतिः । १ । ४ । ३० । जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ।

५९४ । भुवः प्रभवः । १ । ४ । ३१ । भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशत इत्यर्थः । 'ल्यब्लोपे कर्मण्यधिकरणे च' (वा १४७४--१४७५) । प्रासादात्प्रेक्षते आसनात्प्रेक्षते । प्रासादमारुह्य, आसने उपविश्य, प्रेक्षत इत्यर्थः । श्वशुराज्जिह्रेति श्वशुरं वीक्ष्येत्यर्थः । 'गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्' (वा ५०४१) । कस्मात्त्वम् । नद्याः । 'यतश्चाध्वकालनिर्माणं तत्र पञ्चमी' (वा १४७७) । 'तद्युक्तादध्वनः प्रथमासप्तम्यौ' (वा १४७९) । 'कालात्सप्तमी च वक्तव्या' (वा १४७८) । वनाद्ग्रामो योजनं-योजने वा । कार्तिक्या आग्रहायणी मासे ।

५९५ । अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते । २ । ३ । २९ । एतैर्योगे पञ्चमी स्यात् । 'अन्य-' इत्यर्थग्रहणम् । 'इतर'ग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः तेन संप्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । 'तस्य परमाम्रेडितम्' (सू ८३) इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि 'षष्ठ्यतसर्थ-' (सू ६०९) इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक्-प्रत्यग्वा ग्रामात् । आच् । दक्षिणा ग्रामात् । आहि । दक्षिणाहि ग्रामात् । 'अपादाने पञ्चमी' (सू ५८७) इति सूत्रे 'कार्तिक्याः प्रभृति' इति भाष्यप्रयोगात्प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति-आरभ्य वा सेव्यो हरिः । 'अपपरिबहिः-' (सू ६६६) इति समासविधानाज्ज्ञापकाद्बहिर्योगे पञ्चमी । ग्रामाद्बहिः ।

५९६ । अपपरी वर्जने । १ । ४ । ८८ । एतौ वर्जने कर्मप्रवचनीयौ स्तः ।

५९७ । आङ् मर्यादावचने । १ । ४ । ८९ । आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ।

५९८ । पञ्चम्यपाङ्परिभिः । २ । ३ । १० । एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परि हरेः, संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि । आ मुक्तेः संसारः । आ सकलाद्ब्रह्म ।

५९९ । प्रतिः प्रतिनिधिप्रतिदानयोः । १ । ४ । ९२ । एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ।

६०० । प्रतिनिधिप्रतिदाने च यस्मात् । २ । ३ । ११ । अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ।

६०१ । अकर्तर्यृणे पञ्चमी । २ । ३ । २४ । कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् । शताद्बद्धः । 'अकर्तरि' किम् । शतेन बन्धितः ।

६०२ । विभाषा गुणेऽस्त्रियाम् । २ । ३ । २५ । गुणे हेतावस्त्रीलिङ्गे पञ्चमी

१ भाष्ये तु 'प्रश्नाख्यानयोश्च' (वा १४७८) इति वार्तिकमेतदर्थं वर्तते ।

स्यात् । जाड्यात्-जाड्येन वा बद्धः । 'गुणे' किम् । धनेन कुलम् । 'अस्त्रियाम्' किम् । बुद्ध्या मुक्तः । 'विभाषा' इति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ।

६०३ । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । २ । ३ । ३२ । एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीये चानुवर्तेते पृथग्रामेण-रामात्-रामं वा । एवं विना नाना ।

६०४ । करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य । २ । ३ । ३३ । एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः ।

६०५ । दूरान्तिकार्थेभ्यो द्वितीया च । २ । ३ । ३५ । एभ्यो द्वितीया स्याच्चात्पञ्चमी-तृतीये च । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं-दूरात्-दूरेण वा । अन्तिकम्-अन्तिकात्-अन्तिकेन वा । 'असत्त्ववचनस्य' इत्यनुवृत्तेर्नेह । दूरः पन्थाः ।

इति पञ्चमी ।

६०६ । षष्ठी शेषे । २ । ३ । ५० । कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादि-संबन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि संबन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ।

६०७ । षष्ठी हेतुप्रयोगे । २ । ३ । २६ । हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ।

६०८ । सर्वनाम्नस्तृतीया च । २ । ३ । २७ । सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात्षष्ठी च । केन हेतुना वसति । कस्य हेतोः । 'निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' (वा १४७३) । किं निमित्तं वसति । केन निमित्तेन । कस्मै निमित्तायेत्यादि । एवं 'किं कारणम्' 'को हेतुः' 'किं प्रयोजनम्' इत्यादि । 'प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः' । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ।

६०९ । षष्ठ्यतसर्थप्रत्ययेन । २ । ३ । ३० । एतद्योगे षष्ठी स्यात् । '-दिक्छब्द-' (सू ५९९) इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ।

६१० । एनपा द्वितीया । २ । ३ । ३१ । एनबन्तेन योगे द्वितीया स्यात् । 'एनपा' इति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं-ग्रामस्य वा । एवमुत्तरेण ।

६११ । दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् । २ । ३ । ३४ । एतैर्योगे षष्ठी स्यात्पञ्चमी च । दूरं निकटं ग्रामस्य-ग्रामाद्वा ।

६१२ । ज्ञोऽविदर्थस्य करणे । २ । ३ । ५१ । जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ।

६१३ । अधीगर्थदयेशां कर्मणि । २ । ३ । ५२ । एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनमीशनं वा ।

६१४ । कृञः प्रतियत्ने । २ । ३ । ५३ । प्रतियत्नो गुणाधानम् । कृञः कर्मणि शे
षष्ठी स्याद्गुणाधाने । एधो दकस्योपस्करणम् ।

६१५ । रुजार्थानां भाववचनानामज्वरेः । २ । ३ । ५४ । भावकर्तृकाणां ज्वरि
तानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा । 'अज्वरिसन्ताप्योरि
वाच्यम्' (वा १५०७) । रोगस्य चौरज्वरः, चौरसंतापो वा । रोगकर्तृकं चौरसंबन्धि ज्वरा-
दिकमित्यर्थः ।

६१६ । आशिषि नाथः । २ । ३ । ५५ । आशीरर्थस्य नाथतेः शेषे कर्मणि ष
स्यात् । सर्पिषो नाथनम् । 'आशिषि' इति किम् । माणवकनाथनम् । तत्संबन्धि
याच्ञेत्यर्थः ।

६१७ । जासिनिप्रहणनाटक्राथपिषां हिंसायाम् । २ । ३ । ५६ । हिंसार्था
मेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा
चौरस्य निप्रहणनम्-प्रणिहननम्-निहननम्-प्रहणनं वा । 'नट अवस्यन्दने' चुरादिः ।
चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । 'हिंसायाम्' किम् । धानापेषणम्

६१८ । व्यवहृपणोः समर्थयोः । २ । ३ । ५७ । शेषे कर्मणि षष्ठी स्यात् । द्यूते क्र
विक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । 'समर्थयोः' किम्
शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ।

६१९ । दिवस्तदर्थस्य । २ । ३ । ५८ । द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य
दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । 'तदर्थस्य' किम् । ब्राह्मणं दीव्य
स्तौतीत्यर्थः ।

६२० । विभाषोपसर्गे । २ । ३ । ५९ । पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीव्यति

६२१ । प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने । २ । ३ । ६१ । देवतासंप्रदानकेऽर्थे व
मानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हवि
वपाया मेदसः प्रेष्य अनुब्रूहि वा ।

६२२ । कृत्वोर्थप्रयोगे कालेऽधिकरणे । २ । ३ । ६४ । कृत्वोर्थानां प्रयोगे का
वाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । 'शेषे' कि
द्विरहन्यध्ययनम् ।

६२३ । कर्तृकर्मणोः कृति । २ । ३ । ६५ । कृद्योगे कर्तरि कर्मणि च षष्ठी स्या
कृष्णस्य कृतिः । जगतः कर्ता कृष्णः । 'गुणकर्मणि वेष्यते' (वा ५०४२) । नेताश्व
स्रुघ्नस्य-स्रुघ्नं वा । 'कृति' किम् । तद्धिते मा भूत् । कृतपूर्वी कटम् ।

६२४ । उभयप्राप्तौ कर्मणि । २ । ३ । ६६ । उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्म
षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन । 'स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः' (वा १५१३)
भेदिका बिभित्सा वा रुद्रस्य जगतः । 'शेषे विभाषा' (वा १५१३) । स्त्रीप्रत्

---

१ अत्र च 'अथेह कथं भवितव्यम्-नेताश्वस्य स्रुघ्नम्-इति, आहोस्वित्-नेताश्व
स्रुघ्नस्य-इति । उभयथा गोणिकापुत्रः' इति 'अकथित-'(१ । ४ । ५१) सूत्रभाष्यमूलि
प्रधाने नियता षष्ठी गुणकर्मणि वेष्यते' इति शिष्टोक्तिरेव मानम् ।

इत्येके। विचित्रा जगतः कृतिर्हरेः—हरिणा वा। 'केचिदविशेषेण विभाषामिच्छन्ति'। शब्दानामनुशासनमाचार्येण—आचार्यस्य वा।

६२५। क्तस्य च वर्तमाने। २। ३। ६७। वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात्। 'नलोक–' (सू ६२७) इति निषेधस्यापवादः। राज्ञां मतो बुद्धः पूजितो वा।

६२६। अधिकरणवाचिनश्च। २। ३। ६८। क्तस्य योगे षष्ठी स्यात्। इदमेषामासितं शयितं गतं भुक्तं वा।

६२७। न लोकाव्ययनिष्ठाखलर्थतृनाम्। २। ३। ६९। एषां प्रयोगे षष्ठी न स्यात्। लादेशः। कुर्वन्–कुर्वाणो वा सृष्टिं हरिः। उः। हरिं दिदृक्षुः–अलंकरिष्णुर्वा। उकः। दैत्यान्घातुको हरिः। 'कमेरनिषेधः' (वा १९१९)। लक्ष्म्याः कामुको हरिः। अव्ययम्। जगत्सृष्ट्वा। सुखं कर्तुम्। निष्ठा। विष्णुना हता दैत्याः। दैत्यान्हतवान्विष्णुः। खलर्थाः। ईषत्करः प्रपञ्चो हरिणा। 'तृन्' इति प्रत्याहारः। 'शतृशानचौ' इति तृशब्दादारभ्य तृनो नकारात्। शानन्। सोमं पवमानः। चानश्। आत्मानं मण्डयमानः। शतृ। वेदमधीयन्। तृन्। कर्ता लोकान्। 'द्विषः शतुर्वा' (वा १९२२)। मुरस्य–मुरं वा द्विषन्। 'सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः'। शेषे षष्ठी तु स्यादेव। ब्राह्मणस्य कुर्वन्। नरकस्य जिष्णुः।

६२८। अकेनोर्भविष्यदाधमर्ण्ययोः। २। ३। ७०। भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात्। सतः पालकोऽवतरति। व्रजं गामी। शतं दायी।

६२९। कृत्यानां कर्तरि वा। २। ३। ७१। षष्ठी वा स्यात्। मया–मम वा सेव्यो हरिः। 'कर्तरि' इति किम्। गेयो माणवकः साम्नाम्। 'भव्यगेय–' (सू २८९४) इति कर्तरि यद्विधानादनभिहितं कर्म। अत्र योगो विभज्यते। 'कृत्यानाम्'। 'उभयप्राप्तौ' इति 'नः' इति चानुवर्तते। तेन नेतव्या व्रजं गावः कृष्णेन। ततः 'कर्तरि वा'। उक्तोऽर्थः।

६३०। तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्। २। ३। ७२। तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी। तुल्यः सदृशः समो वा कृष्णस्य–कृष्णेन वा। 'अतुलोपमाभ्याम्' किम्। तुला–उपमा वा कृष्णस्य नास्ति।

६३१। चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः। २। ३। ७३। एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि। आयुष्यं चिरंजीवितं कृष्णाय–कृष्णस्य वा भूयात्। एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात्। 'आशिषि' किम्। देवदत्तस्यायुष्यमस्ति। व्याख्यानात्सर्वत्रार्थग्रहणम्। मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः।

इति षष्ठी।

६३२। आधारोऽधिकरणम्। १। ४। ४५। कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात्।

६३३। सप्तम्यधिकरणे च। २। ३। ३६। अधिकरणे सप्तमी स्यात्। चकाराद्दूरान्तिकार्थेभ्यः। औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा। कटे आस्ते। स्थाल्यां पचति। मोक्षे इच्छास्ति। सर्वस्मिन्नात्मास्ति। वनस्य दूरेऽन्तिके वा। 'दूरान्तिकार्थेभ्यः–' (सू ६०५) इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः। 'क्तस्येन्विषयस्य

कर्मण्युपसंख्यानम्' (वा १४८५)। अधीती व्याकरणे। अधीतमनेनेति विग्रहे 'इष्टादिभ्य
(सू १८८८) इति कर्तरीनिः। 'साध्वसाधुप्रयोगे च' (वा १४८६)। साधुः कृष्णो मातरि।
असाधुर्मातुले। 'निमित्तात्कर्मयोगे' (वा १४९०)। निमित्तमिह फलम्। योगः संयोगस
वायात्मकः।

'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्।
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः'॥ [इति भाष्यम्।]

हेतौ तृतीयात्र प्राप्ता। सीमाण्डकोशः। पुष्कलको गन्धमृगः। 'योगविशेषे' किम्। वेतनेन धान्यं लुनाति।

६३४। यस्य च भावेन भावलक्षणम्। २। ३। ३७। यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात्। गोषु दुह्यमानासु गतः। 'अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च' (वा १४८७-१४८८)। सत्सु तरत्सु असन्त आसते। असत्सु तिष्ठत्सु सन्तस्तरन्ति। सत्सु तिष्ठत्सु असन्तस्तरन्ति। असत्सु तरत्सु सन्तस्तिष्ठन्ति।

६३५। षष्ठी चानादरे। २। ३। ३८। अनादराधिके भावलक्षणे षष्ठीसप्तम्यौ स्तः। रुदति रुदतो वा प्राव्राजीत्। रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः।

६३६। स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च। २। ३। ३९। एतैः स भिर्योगे षष्ठीसप्तम्यौ स्तः। षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम्। गवां-गोषु स्वामी। गवां-गोषु वा प्रसूतः। गा एवानुभवितुं जात इत्यर्थः।

६३७। आयुक्तकुशलाभ्यां चासेवायाम्। २। ३। ४०। आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे। आयुक्तो व्यापारितः। आयुक्तः-कुशलो वा हरिपूजने-हरिपूजनस्य वा। 'आसेवायाम्' किम्। आयुक्तो गौः शकटे। ईषद्युक्त इत्यर्थः।

६३८। यतश्च निर्धारणम्। २। ३। ४१। जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः। नृणां-नृषु वा ब्राह्मणः श्रेष्ठः। गवां-गोषु वा कृष्णा बहुक्षीरा। गच्छतां-गच्छत्सु वा धावञ्छीघ्रः। छात्राणां-छात्रेषु मैत्रः पटुः।

६३९। पञ्चमी विभक्ते। २। ३। ४२। विभागो विभक्तं निर्धार्यमाणस्य यत्र भेद तत्र पञ्चमी स्यात्। माथुराः पाटलिपुत्रकेभ्य आढ्यतराः।

६४०। साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः। २। ३। ४३। आभ्यां योगे सप्तमी स्यादर्चायाम्। न तु प्रतेः प्रयोगे। मातरि साधुर्निपुणो वा। 'अर्चायाम्' किम्। निपुणो राज्ञो भृत्यः। इह तत्त्वकथने तात्पर्यम्। 'अप्रत्यादिभिरिति वक्तव्यम्' (वा १४९३) साधुर्निपुणो वा मातरं प्रति पर्यनु वा।

६४१। प्रसितोत्सुकाभ्यां तृतीया च। २। ३। ४४। आभ्यां योगे तृतीया स्याच्चात् सप्तमी। प्रसित उत्सुको हरिणा-हरौ वा।

६४२। नक्षत्रे च लुपि। २। ३। ४५। नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमान प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे। 'मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत्'। मूले श्रवण इति वा। 'लुपि' किम्। पुष्ये शनिः।

६४३ । सप्तमीपञ्चम्यौ कारकमध्ये । २ । ३ । ७ । शक्तिद्वयमध्ये यौ कालाध्वानौ ताभ्यामेते स्तः । अद्य भुक्त्वायं द्व्यहे-द्व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे-क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । 'तदस्मिन्नधिकम्-' (सू. १८४६) इति 'यस्मादधिकम्-' (सू. ६४५) इति च सूत्रनिर्देशात् । लोके-लोकाद्वाधिको हरिः ।

६४४ । अधिरीश्वरे । १ । ४ । ९७ । स्वस्वामिसंबन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ।

६४५ । यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । २ । ३ । ९ । अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । 'सप्तमी शौण्डैः' (सू. ७१७) इति समासपक्षे तु रामाधीना । 'अषडक्ष-' (सू. २०७९) इत्यादिना खः ।

६४६ । विभाषा कृञि । १ । ४ । ९८ । अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् 'तिङि चोदात्तवति' (सू. ३९७८) इति निघातो न ।

इति सप्तमी ।

इति कारकादिविभक्तिप्रकरणम् ।

अथाव्ययीभावसमासप्रकरणम् ।

६४७ । समर्थः पदविधिः । २ । १ । १ । पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः ।

६४८ । प्राक्कडारात्समासः । २ । १ । ३ । 'कडाराः कर्मधारये' (सू. ७५१) इत्यतः प्राक्समास इत्यधिक्रियते ।

६४९ । सह सुपा । २ । १ । ४ । 'सह' इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टसिद्ध्यर्थत्वात्कातिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । 'सुपा' । सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ।

६५० । सुपो धातुप्रातिपदिकयोः । २ । ४ । ७१ । एतयोरवयवस्य सुपो लुक्स्यात् । 'भूतपूर्वे चरट्' (सू. १९९९) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः । 'इवेन समासो विभक्त्यलोपश्च' (वा १२३६, १३४१) । जीमूतस्येव ।

६५१ । अव्ययीभावः । २ । १ । ५ । अधिकारोऽयम् ।

६५२ । अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु । २ । १ । ६ । 'अव्ययम्' इति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते सोऽव्ययीभावः ।

६५३। प्रथमानिर्दिष्टं समास उपसर्जनम्। १। २। ४३। समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्।

६५४। उपसर्जनं पूर्वम्। २। २। ३०। समास उपसर्जनं प्राक्प्रयोज्यम्।

६५५। एकविभक्ति चापूर्वनिपाते। १। २। ४४। विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात्, न तु तस्य पूर्वनिपातः।

६५६। गोस्त्रियोरुपसर्जनस्य। १। २। ४८। उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। 'अव्ययीभावश्च' (सू ४५९) इत्यव्ययत्वम्।

६५७। नाव्ययीभावादतोऽम्त्वपञ्चम्याः। २। ४। ८३। अदन्तादव्ययीभावात्सुपो न लुक्, तस्य तु पञ्चमीं विनाऽमादेशश्च स्यात्। दिशयोर्मध्येऽपदिशम्। 'क्लीबेऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्' इत्यमरः।

६५८। तृतीयासप्तम्योर्बहुलम्। २। ४। ८४। अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात्। अपदिशम्-अपदिशेन। अपदिशम्-अपदिशे। बहुलग्रहणात् 'सुमद्रम्' 'उन्मत्तगङ्गम्' इत्यादौ सप्तम्या नित्यमम्भावः। 'विभक्ति-' इत्यादेरयमर्थः। विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः। 'विभक्तौ तावत्'। हरौ इत्यधिहरि। सप्तम्यर्थस्यैवात्र द्योतकोऽधिः। हरि ङि अधि इत्यलौकिकं विग्रहवाक्यम्। अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी।

६५९। अव्ययीभावश्च। २। ४। १८। अयं नपुंसकं स्यात्। 'ह्रस्वो नपुंसके प्रातिपदिकस्य' (सू ३१८)। गोपायतीति गाः पातीति वा गोपास्तस्मिन्नित्यधिगोपम्। समीपे कृष्णस्य समीपमुपकृष्णम्। समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः 'अभितःपरितः-' (वा १४४२) 'अन्यारात्'-(सू ५९९) इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात्। मद्राणां समृद्धिः सुमद्रम्। यवनानां व्यृद्धिर्दुर्यवनम्। विगता ऋद्धिर्व्यृद्धिः। मक्षिकाणामभावो निर्मक्षिकम्। हिमस्यात्ययोऽतिहिमम्। अत्ययो ध्वंसः। निद्रा संप्रति न युज्यत इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इतिहरि। विष्णोः पश्चादनुविष्णु। पश्चाच्छब्दस्य तु नायं समासः। 'ततः पश्चात्स्रंस्यते' इति [१।१।५७ सूत्रे] भाष्यप्रयोगात्। योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। अनुरूपम्। रूपस्य योग्यमित्यर्थः। अर्थमर्थं प्रति प्रत्यर्थम्। प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भं वाक्यमपि। शक्तिमनतिक्रम्य यथाशक्ति। हरेः सादृश्यं सहरि। वक्ष्यमाणेन सहस्य सः। ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपदिति विग्रहे।

६६०। अव्ययीभावे चाकाले। ६। ३। ८१। सहस्य सः स्यादव्ययीभावे न तु काले। सचक्रम्। काले तु सहपूर्वाह्णम्। सदृशः सख्या ससखि। यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्। क्षत्राणां संपत्तिः सक्षत्रम्। ऋद्धेराधिक्यं समृद्धिः। अनुरूप आत्मभावः संपत्तिरिति भेदः। तृणमप्यपरित्यज्य सतृणमत्ति। साकल्येनेत्यर्थः। न त्वत्र तृणभक्षणे तात्पर्यम्। अन्ते। अग्निग्रन्थपर्यन्तमधीते साग्नि।

६६१। यथासादृश्ये। २। १। ७। असादृश्य एव यथाशब्दः समस्यते। तेनेह न

यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन 'सादृश्य' इति वा 'यथार्थे' इति वा प्राप्तं निषिध्यते ।

६६२ । **यावदवधारणे** । २ । १ । ८ । यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामा यावच्छ्लोकम् ।

६६३ । **सुप्प्रतिना मात्रार्थे** । २ । १ । ९ । शाकस्य लेशः शाकप्रति । 'मात्रार्थे' किम् । वृक्षं प्रति विद्योतते विद्युत् ।

६६४ । **अक्षशलाकासंख्याः परिणा** । २ । १ । १० । द्यूतव्यवहारे पराजये एवायं समासः । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि ।

६६५ । **विभाषा** । २ । १ । ११ । अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । 'सुप्सुपा' इति तु न नित्यसमासः । 'अव्ययम्' इत्यादिसमासविधानाज्ज्ञापकात् ।

६६६ । **अपपरिबहिरञ्चवः पञ्चम्या** । २ । १ । १२ । अपविष्णु संसारः–अप विष्णोः । परिविष्णु–परि विष्णोः । बहिर्वनम्–बहिर्वनात् । प्राग्वनम्–प्राग्वनात् ।

६६७ । **आङ्मर्यादाभिविध्योः** । २ । १ । १३ । एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः–आ मुक्तेः । आबालं हरिभक्तिः–आ बालेभ्यः ।

६६८ । **लक्षणेनाभिप्रती आभिमुख्ये** । २ । १ । १४ । आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्राग्वत् । अभ्यग्नि शलभाः पतन्ति अग्निमभि । प्रत्यग्नि । अग्निं प्रति ।

६६९ । **अनुर्यत्समया** । २ । १ । १५ । यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ।

६७० । **यस्य चायामः** । २ । १ । १६ । यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः ।

६७१ । **तिष्ठद्गुप्रभृतीनि च** । २ । १ । १७ । एतानि निपात्यन्ते । तिष्ठन्ति गावो यस्मिन्काले स तिष्ठद्गु दोहनकालः । आयतीगवम् । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ।

६७२ । **पारे मध्ये षष्ठ्या वा** । २ । १ । १८ । पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय–गङ्गापारात् । मध्येगङ्गात्–गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया मध्यात् ।

६७३ । **संख्या वंश्येन** । २ । १ । १९ । वंशो द्विधा, विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ । द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशतिभारद्वाजम् ।

६७४ । **नदीभिश्च** । २ । १ । २० । नदीभिः संख्या प्राग्वत् । 'समाहारे चायमिष्यते' (वा १२४६) । सप्तगङ्गम् । द्वियमुनम् ।

६७५ । **अन्यपदार्थे च संज्ञायाम्** । २ । १ । २१ । अन्यपदार्थे विद्यमानं सुबन्तं

---

१ अत्र १२४२ वार्तिकं मानम् ।

नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ।

६७६ । समासान्ताः । ५ । ४ । ६८ । इत्यधिकृत्य ।

६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः । ५ । ४ । १०७ । शरदादिभ्यष्टच्स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद् । कियत् । 'जराया जरस् च' (ग १४७) । उपजरसम् । 'प्रतिपरसमनुभ्योऽक्ष्णः' (ग १४८) । 'पस्येति च' (सू ३११) । प्रत्यक्षम् । 'अक्ष्णः परम्' इति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभावः । 'परोक्षे लिट्' (सू २१७१) इति निपातनात्परस्यौकारादेशः । परोक्षम् । 'परोक्षा क्रिया' इत्यादि तु अर्शआद्यचि । समक्षम् । अन्वक्षम् ।

६७८ । अनश्च । ५ । ४ । १०८ । अन्नन्तादव्ययीभावाट्टच्स्यात् ।

६७९ । नस्तद्धिते । ६ । ४ । १४४ । नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् ।

६८० । नपुंसकादन्यतरस्याम् । ५ । ४ । १०९ । अन्नन्तं यत्क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम्–उपचर्म ।

६८१ । नदीपौर्णमास्याग्रहायणीभ्यः । ५ । ४ । ११० । वा टच्स्यात् । उपनदम्–उपनदि । उपपौर्णमासम्–उपपौर्णमासि । उपाग्रहायणम्–उपाग्रहायणि ।

६८२ । झयः । ५ । ४ । १११ । झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम्–उपसमित् ।

६८३ । गिरेश्च सेनकस्य । ५ । ४ । ११२ । गिर्यन्तादव्ययीभावाट्टज्वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम्–उपगिरि ।

इत्यव्ययीभावसमासप्रकरणम् ।

अथ तत्पुरुषसमासप्रकरणम् ।

६८४ । तत्पुरुषः । २ । १ । २२ । अधिकारोऽयम् । प्राग्बहुव्रीहेः ।

६८५ । द्विगुश्च । २ । १ । २३ । द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् 'संख्यापूर्वो द्विगुश्च' इति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ।

६८६ । द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । २ । १ । २४ । द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णाश्रितः दुःखमतीतो दुःखातीतः । 'गम्यादीनामुपसंख्यानम्' (वा १२४७) । ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुरन्नबुभुक्षुः ।

६८७ । स्वयं क्तेन । २ । १ । २५ । 'द्वितीया–' (सू ६८६) इति न संबध्यतेऽयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ।

६८८। खट्वा क्षेपे। २। १। २६। खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम्। खट्वारूढो जाल्मः। नित्यसमासोऽयम्। न हि वाक्येन निन्दा गम्यते।

६८९। सामि। २। १। २७। सामिकृतम्।

६९०। कालाः। २। १। २८। 'क्तेन' इत्येव। अनत्यन्तसंयोगार्थं वचनम्। मासप्रमितः प्रतिपच्चन्द्रः। मासं परिच्छेत्तुमारब्धवानित्यर्थः।

६९१। अत्यन्तसंयोगे च। २। १। २९। 'कालाः' इत्येव। अक्तान्तार्थं वचनम्। मुहूर्तं सुखं मुहूर्तसुखम्।

६९२। तृतीया तत्कृतार्थेन गुणवचनेन। २। १। ३०। 'तत्कृत—' इति लुप्ततृतीयाकम्। तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत्। शङ्कुलया खण्डः शङ्कुलाखण्डः। धान्येनार्थो धान्यार्थः। 'तत्कृत—' इति किम्। अक्ष्णा काणः।

६९३। पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः। २। १। ३१। तृतीयान्तमेतैः प्राग्वत्। मासपूर्वः। मातृसदृशः। पितृसमः। ऊनार्थे। माषोनं कार्षापणम्। माषविकलम्। वाक्कलहः। आचारनिपुणः। गुडमिश्रः। आचारश्लक्ष्णः। 'मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्'। 'मिश्रं चानुपसर्गमसंधौ' (सू ३८८८) इत्यत्रानुपसर्गग्रहणात्। गुडसंमिश्रा धानाः। 'अवरस्योपसंख्यानम्' (वा १२५६)। मासेनावरो मासावरः।

६९४। कर्तृकरणे कृता बहुलम्। २। १। ३२। कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रातो हरित्रातः। नखैर्भिन्नो नखभिन्नः। 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' (प २९)। नखनिर्भिन्नः। 'कर्तृकरणे' इति किम्। भिक्षाभिरुषितः। हेतावेषा तृतीया। बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम्। तेन 'दात्रेण लूनवान्' इत्यादौ न। 'कृता' किम्। काष्ठैः पचतितराम्।

६९५। कृत्यैरधिकार्थवचने। २। १। ३३। स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनम्। तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत्। वातच्छेद्यं तृणम्। काकपेया नदी।

६९६। अन्नेन व्यञ्जनम्। २। १। ३४। संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत्। दध्ना ओदनो दध्योदनः। इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम्।

६९७। भक्ष्येण मिश्रीकरणम्। २। १। ३५। गुडेन धाना गुडधानाः। मिश्रणक्रियाद्वारा सामर्थ्यम्।

६९८। चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः। २। १। ३६। चतुर्थ्यन्तार्थाय यत्तद्वाचिनार्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत्। 'तदर्थेन प्रकृतिविकृतिभाव एव'। बलिरक्षितग्रहणाज्ज्ञापकात्। यूपाय दारु यूपदारु। नेह। रन्धनाय स्थाली। अश्वघासादयस्तु षष्ठीसमासाः। 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्' (वा १२७३–१२७४)। द्विजायायं द्विजार्थः सूपः। द्विजार्था यवागूः। द्विजार्थं पयः। भूतबलिः। गोहितम्। गोसुखम्। गोरक्षितम्।

६९९। पञ्चमी भयेन। २। १। ३७। चोराद्भयं चोरभयम्। 'भयभीतभीतिभीभिरिति वाच्यम्' (वा १२७९)। वृकभीतः।

७००। अपेतापोढमुक्तपतितापत्रस्तैरल्पशः। २। १। ३८। एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः। सुखापेतः। कल्पनापोढः। चक्रमुक्तः। स्वर्गपतितः। तरंगापत्रस्तः। 'अल्पशः' किम्। प्रासादात्पतितः।

७०१। स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन। २। १। ३९। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रादागतः। 'पञ्चम्याः स्तोकादिभ्यः' (सू ९५९) इत्यलुक्।

७०२। षष्ठी। २। २। ८। राज्ञः पुरुषो राजपुरुषः।

७०३। याजकादिभिश्च। २। २। ९। एभिः षष्ठ्यन्तं समस्यते। 'तृजकाभ्यां कर्तरि' (सू ७०९) इत्यस्य प्रतिप्रसवोऽयम्। ब्राह्मणयाजकः। देवपूजकः। 'गुणात्तरेण तरलोपश्चेति वक्तव्यम्' (वा ३८४१)। तरबन्तं यद्गुणवाचि तेन सह समासस्तरलोपश्च। 'न निर्धारणे' (सू ७०४) इति 'पूरणगुण—' (सू ७०५) इति च निषेधस्य प्रतिप्रसवोऽयम्। सर्वेषां श्वेततरः सर्वश्वेतः। सर्वेषां महत्तरः सर्वमहान्। 'कृद्योगा च षष्ठी समस्यत इति वाच्यम्' (वा १३१३) इध्मस्य व्रश्चन इध्मव्रश्चनः।

७०४। न निर्धारणे। २। २। १०। निर्धारणे या षष्ठी सा न समस्यते। नृणां द्विजः श्रेष्ठः। 'प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम्' (वा १३२०)। सर्पिषो ज्ञानम्।

७०५। पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन। २। २। ११। पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते। पूरणे। सतां षष्ठः। गुणे। काकस्य कार्ष्ण्यम्। ब्राह्मणस्य शुक्लाः। यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेदमुदाहरणम्। 'अनित्योऽयं गुणेन निषेधः'। 'तदशिष्यं संज्ञाप्रमाणत्वात्' (सू १२९५) इत्यादिनिर्देशात्। तेन 'अर्थगौरवम्', 'बुद्धिमान्द्यम्' इत्यादि सिद्धम्। सुहितार्थास्तृप्त्यर्थाः। फलानां सुहितः। तृतीयासमासस्तु स्यादेव। स्वरे विशेषः। सत्। द्विजस्य कुर्वन्–कुर्वाणो वा। किंकर इत्यर्थः। अव्ययम्। ब्राह्मणस्य कृत्वा। पूर्वोत्तरसाहचर्यात्कृदव्ययमेव गृह्यते। तेन 'तदुपरि' इत्यादि सिद्धमिति रक्षितः। तव्यः। ब्राह्मणस्य कर्तव्यम्। तव्यता तु भवत्येव। स्वकर्तव्यम्। स्वरे भेदः। समानाधिकरणे। तक्षकस्य सर्पस्य। विशेषणसमासस्त्विह बहुलग्रहणान्न। 'गोर्धेनोः' इत्यादिषु 'पोटायुवति–'(सू ७४४) इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्बाधकः षष्ठीसमासः प्राप्तः। सोऽप्यनेन वार्यते।

७०६। क्तेन च पूजायाम्। २। २। १२। 'मतिबुद्धि–' (सू ३०८९) इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते। राज्ञां मतो बुद्धः पूजितो वा। 'राजपूजितः' इत्यादौ तु भूते क्तान्तेन सह तृतीयान्तस्य समासः।

७०७। अधिकरणवाचिना च। २। २। १३। क्तेन षष्ठी न समस्यते। इदमेषामासितं गतं भुक्तं वा।

७०८। कर्मणि च। २। २। १४। 'उभयप्राप्तौ कर्मणि' (सू ६२४) इति या षष्ठी सा न समस्यते। आश्चर्यो गवां दोहोऽगोपेन।

७०९ । तृजकाभ्यां कर्तरि । २ । २ । १५ । कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । 'कर्तरि' किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य याजकादित्वात्समासः । भूभर्ता । कथं तर्हि 'घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः' इति । 'शेषषष्ठ्या समासः' इति कैयटः ।

७१० । कर्तरि च । २ । २ । १६ । कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे । कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ।

७११ । नित्यं क्रीडाजीविकयोः । २ । २ । १७ । एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । 'संज्ञायाम्' (सू ३२८६) इति भावे ण्वुल् । जीविकायां दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां 'तृजकाभ्यां कर्तरि' (सू ७०९) इति निषेधे प्राप्ते वचनम् ।

७१२ । पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । २ । २ । १ । अवयविना सह पूर्वादयः समस्यन्ते । एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । 'एकदेशिना' किम् । पूर्वं नभेः कायस्य । 'एकाधिकरणे' किम् । पूर्वश्छात्राणाम् । 'सर्वोऽप्येकदेशोऽह्ना समस्यते' । 'संख्याविसाय–' (सू २३८) इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु 'सर्व एकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन 'मध्यरात्रः', 'उपारता पश्चिमरात्रगोचरात्' इत्यादि सिद्धम् । इत्याहुः ।

७१३ । अर्धं नपुंसकम् । २ । २ । २ । समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत् । एकविभक्त्यावषष्ठ्यन्तवचनम् (वा ६७३) एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन 'पञ्चखट्वी' इत्यादि सिध्यति । अर्धं पिप्पल्या अर्धपिप्पली । 'क्लीबे' किम् । ग्रामार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ।

७१४ । द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । २ । २ । ३ । एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । 'एकदेशिना' किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यां ग्रहणसामर्थ्यात् 'पूरणगुण–'(सू ७०५) इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ।

७१५ । प्राप्तापन्ने च द्वितीयया । २ । २ । ४ । पक्षे 'द्वितीया श्रित–' (सू ६८६) इति समासः । प्राप्तो जीविकां प्राप्तजीविकः–जीविकाप्राप्तः । आपन्नजीविकः–जीविकापन्नः । इह सूत्रे 'द्वितीयया अ' इति छित्त्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्नजीविका ।

७१६ । कालाः परिमाणिना । २ । २ । ५ । परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य यस्य स मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्येति विग्रहे 'उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्' (वा १२८८) । द्वे अहनी जातस्य यस्य स द्व्यह्नजातः । 'अह्नोऽह्न–' (७९०) इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु 'न संख्यादेः समाहारे' (सू ७९३) इति निषेधः ।

७१७ । सप्तमी शौण्डैः । २ । १ । ४० । सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु

'-अध्युत्तरपदात्-' (सू २०७९) इति खः।
शौण्डोऽक्षशौण्डः। अधिशब्दोऽत्र पठ्यते।
ईश्वराधीनः।

७१८। सिद्धशुष्कपक्वबन्धैश्च।२।१।४१। एतैः सप्तम्यन्तं प्राग्वत्। सांकाश्य-
सिद्धः। आतपशुष्कः। स्थालीपक्वः। चक्रबन्धः।

७१९। ध्वाङ्क्षेण क्षेपे।२।१।४२। ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दा-
याम्। तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः। तीर्थकाक इत्यर्थः।

७२०। कृत्यैर्ऋणे।२।१।४३। सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके
मासेदेयमृणम्। ऋणग्रहणं नियोगोपलक्षणार्थम्। पूर्वाह्णेगेयं साम।

७२१। संज्ञायाम्।२।१।४४। सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम्। वाक्येन संज्ञान-
गमान्नित्यसमासोऽयम्। अरण्येतिलकाः। वनेकशेरुकाः। 'हलदन्तात्सप्तम्याः-' (सू ९६६)
इत्यलुक्।

७२२। क्तेनाहोरात्रावयवाः।२।१।४५। अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन
सह प्राग्वत्। पूर्वाह्णकृतम्। अपररात्रकृतम्। 'अवयव' ग्रहणं किम्। अह्नि दृष्टम्।

७२३। तत्र।२।१।४६। 'तत्र' इत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत्। तत्रभुक्तम्।

७२४। क्षेपे।२।१।४७। सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम्। 'अवतप्तेनकुल-
स्थितं त एतत्'।

७२५। पात्रेसमितादयश्च।२।१।४८। एते निपात्यन्ते क्षेपे। पात्रेसमिताः। भोज-
नसमय एव संगता न तु कार्ये। गेहेशूरः। गेहेनर्दी। आकृतिगणोऽयम्। चकारोऽवधा-
रणार्थः। तेनैषां समासान्तरे घटकतया प्रवेशो न। परमाः पात्रेसमिताः।

७२६। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन।२।१।४९।
'विशेषणं विशेष्येण-'(सू ७३६) इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम्। एकशब्दस्य
'दिक्संख्ये संज्ञायाम्' (सू ७२७) इति नियमबाधनार्थं च। पूर्वं स्नातः पश्चादनुलिप्तः
स्नातानुलिप्तः। एकनाथः। सर्वयाज्ञिकाः। जरन्नैयायिकाः। पुराणमीमांसकाः। नवपाठकाः।
केवलवैयाकरणाः।

७२७। दिक्संख्ये संज्ञायाम्।२।१।५०। 'समानाधिकरणेन' इत्यापादपरिसमा-
प्तेरधिकारः। 'संज्ञायामेव' इति नियमार्थं सूत्रम्। पूर्वेषुकामशमी। सप्तर्षयः। नेह। उत्त-
वृक्षाः। पञ्च ब्राह्मणाः।

७२८। तद्धितार्थोत्तरपदसमाहारे च।२।१।५१। तद्धितार्थे विषये उत्तरपदे च
परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा। पूर्वस्यां शालायां भवः पौर्वशालः। समासे
कृते 'दिक्पूर्वपदादसंज्ञायां ञः' (सू १३२८) इति ञः। 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः'
(वा १३७६)। आपरशालः। पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे
उत्तरपदे पूर्वयोस्तत्पुरुषः। तेन शालाशब्द आकार उदात्तः। पूर्वशालाप्रियः। दिक्षु समा-
हारो नास्त्यनभिधानात्। संख्यायास्तद्धितार्थे। षण्णां मातृणामपत्यं षाण्मातुरः। पञ्च
गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते। 'द्वन्द्वतत्पुरुषयोरुत्तर-
पदे नित्यसमासवचनम्' (वा १२८७)।

७२९। गोरतद्धितलुकि। ५। ४। ९२। गोऽन्तात्तत्पुरुषाट्टच्स्यात्समासान्तो न तद्धितलुकि। पञ्चगवधनः। पञ्चानां गवां समाहारः।

७३०। संख्यापूर्वो द्विगुः। २। १। ५२। 'तद्धितार्थ–' (सू ७२८) इत्यत्रोक्तः संख्यापूर्वो द्विगुः स्यात्।

७३१। द्विगुरेकवचनम्। २। ४। १। द्विग्वर्थः समाहार एकवत्स्यात्। 'स नपुंसकम्' (सू ८२१) इति नपुंसकत्वम्। पञ्चगवम्।

७३२। कुत्सितानि कुत्सनैः। २। १। ५३। कुत्स्यमानानि कुत्सनैः सह प्राग्वत्। वैयाकरणखसूचिः। मीमांसकदुर्दुरूढः।

७३३। पापाणके कुत्सितैः। २। १। ५४। पूर्वसूत्रापवादः। पापनापितः। अणककुलालः।

७३४। उपमानानि सामान्यवचनैः। २। १। ५५। घन इव श्यामो घनश्यामः। इह 'पूर्वपदं तत्सदृशे लाक्षणिकम्' इति सूचयितुं लौकिकविग्रह इवशब्दः प्रयुज्यते। पूर्वनिपातनियमार्थं सूत्रम्।

७३५। उपमितं व्याघ्रादिभिः सामान्याप्रयोगे। २। १। ५६। उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति विशेष्यस्य पूर्वनिपातार्थं सूत्रम्। पुरुषव्याघ्रः। नृसोमः। व्याघ्रादिराकृतिगणः। 'सामान्याप्रयोगे' किम्। पुरुषो व्याघ्र इव शूरः।

७३६। विशेषणं विशेष्येण बहुलम्। २। १। ५७। भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात् 'क्वचिन्नित्यम्'। कृष्णसर्पः। 'क्वचिन्न'। रामो जामदग्न्यः।

७३७। पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च। २। १। ५८। पूर्वनिपातनियमार्थमिदम्। पूर्ववैयाकरणः। अपराध्यापकः। 'अपरस्यार्धे पश्चभावो वक्तव्यः' (वा ३२५३)। अपरश्चासावर्धश्च पश्चार्धः। कथम् 'एकवीरः' इति। 'पूर्वकालैक-' (सू ७२६) इति बाधित्वा परत्वादनेन समासे 'वीरैकः' इति हि स्यात्। बहुलग्रहणाद्भविष्यति।

७३८। श्रेण्यादयः कृतादिभिः। २। १। ५९। 'श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम्' (वा १२९६)। अश्रेणयः श्रेणयः कृताः श्रेणीकृताः।

७३९। क्तेन नञ्विशिष्टेनानञ्। २। १। ६०। नञ्विशिष्टेन क्तान्तेनानञ्क्तान्तं समस्यते। कृतं च तदकृतं च कृताकृतम्। 'शाकपार्थिवादीनां सिद्धय उत्तरपदलोपस्योपसंख्यानम्' (वा १३१०)। शाकप्रियः पार्थिवः शाकपार्थिवः। देवब्राह्मणः।

७४०। सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः। २। १। ६१। सद्वैयः। वक्ष्यमाणेन महत आकारः। महावैयाकरणः। 'पूज्यमानैः' किम्। उत्कृष्टो गौः। पङ्कादुद्धृत इत्यर्थः।

७४१। वृन्दारकनागकुञ्जरैः पूज्यमानम्। २। १। ६२। गोवृन्दारकः। 'व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम्।

७४२। कतरकतमौ जातिपरिप्रश्ने। २। १। ६३। कतरकठः। कतमकलापः। 'गोत्रं च चरणैः सह' इति जातित्वम्।

कुत्सितो राजा, किंराजा यो न रक्षति ।

७४३ । किं क्षेपे । २ । १ । ६४ । कुत्सितो राजा, किंराजा यो न रक्षति ।

७४४ । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्याप-
कधूर्तैर्जातिः । २ । १ । ६५ ।

७४५ । तत्पुरुषः समानाधिकरणः कर्मधारयः । १ । २ । ४२ ।

७४६ । पुंवत्कर्मधारयजातीयदेशीयेषु । ६ । ३ । ४२ । कर्मधारये जातीयदेशीययोः
परतो भाषितपुंस्कात्पर ऊङभावो यस्मिंस्तथाभूतं पूर्वं पुंवत् । पुरणीप्रियादिष्वप्राप्तः पुंवद्भा
विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्म
रयादौ प्रतिप्रसूयते । पाचकस्त्री । दत्तभार्या । पञ्चमभार्या । स्त्रौघ्नभार्या । सुकेशभार्या । ब्राह्म
णभार्या । एवं 'पाचकजातीया' 'पाचकदेशीया' इत्यादि । इभपोटा । 'पोटा स्त्रीपुंसलक्षणा'
इभयुवतिः । अग्निस्तोकः । उदश्वित्कतिपयम् । गृष्टिः सकृत्प्रसूता । गोगृष्टिः । धेनुर्नवप्र
तिका । गोधेनुः । वशा वन्ध्या गोवशा । वेहद्गर्भघातिनी । गोवेहत् । बष्कयणी तरु
वत्सा । गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ।

७४७ । प्रशंसावचनैश्च । २ । १ । ६६ । एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोम
चर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नि
तल्लिङ्गा न तु विशेष्यनिघ्नाः । 'जातिः' किम् । कुमारी मतल्लिका ।

७४८ । युवा खलतिपलितवलिनजरतीभिः । २ । १ । ६७ । पूर्वनिपातनियमा
सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिर्युवखलतिः । युव
खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्सामाना
करण्यम् ।

७४९ । कृत्यतुल्याख्या अजात्या । २ । १ । ६८ । भोज्योष्णम् । तुल्यश्वेतः । स
शश्वेतः । 'अजात्या' किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ।

७५० । वर्णो वर्णेन । २ । १ । ६९ । समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ।

७५१ । कडाराः कर्मधारये । २ । २ । ३८ । कडारादयः शब्दाः कर्मधारये वा
प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ।

७५२ । कुमारः श्रमणादिभिः । २ । १ । ७० । कुमारी श्रमणा कुमारश्रमणा । इह
श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञाप
बोध्यम् ।

७५३ । चतुष्पादो गर्भिण्या । २ । १ । ७१ । चतुष्पाज्जातिवाचिनो गर्भिणीश
सह प्राग्वत् । गोगर्भिणी । 'चतुष्पाज्जातिरिति वक्तव्यम्' (वा १३११) । नेह । स्वस्तिम
गर्भिणी ।

७५४ । मयूरव्यंसकादयश्च । २ । १ । ७२ । एते निपात्यन्ते । मयूरो व्यंसकः म
व्यंसकः । व्यंसको धूर्तः । उदक्चावाक्चोच्चावचम् । निश्चितं च प्रचितं च निश्चप्रच
नास्ति किंचन यस्य सोऽकिंचनः । नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो रा
राजान्तरम् । चिदेव चिन्मात्रम् । 'आख्यातमाख्यातेन क्रियासातत्ये' (ग २०) । अश्नी
पिबतेत्येवं सततं यत्राभिधीयते साश्नीतपिबता । पचतभृज्जता । खादतमोदता । 'एहीडाद

ऽन्यपदार्थे' (ग १८)। एहीड इति यस्मिन्कर्मणि तदेहीडम्। एहियवम्। उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सोद्धरोत्सृजा। उद्धमविधमा। असातत्यार्थमिह पाठः। 'जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति' (ग २९)। जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्यं गम्ये समासेन चेत्कर्ताभिधीयत इत्यर्थः। जहिजोडः। जहिस्तम्बः।

७५५। ईषदकृता। २। २। ७। ईषत्पिङ्गलः। 'ईषद्गुणवचनेनेति वाच्यम्' (वा १३१६)। ईषद्रक्तम्।

७५६। नञ्। २। २। ६। नञ्सुपा सह समस्यते।

७५७। नलोपो नञः। ६। ३। ७३। नञो नस्य लोपः स्यादुत्तरपदे। न ब्राह्मणोऽब्राह्मणः।

७५८। तस्मान्नुडचि। ६। ३। ७४। लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्। अनश्वः। अर्थाभावेऽव्ययीभावेन सहायं विकल्प्यते। 'रक्षोहागमलघ्वसंदेहाः प्रयोजनम्' इति 'अद्रुतायामसंहितम्' (वा ११६७) इति च भाष्यवार्तिकप्रयोगात्। तेन 'अनुपलब्धिः', अविवादः', 'अविघ्नम्', इत्यादि सिद्धम्। 'नञो नलोपस्तिङि क्षेपे' (वा ३९८४)। अपचसि त्वं जाल्म। 'नैकधा' इत्यादौ तु नशब्देन 'सह सुपा' (सू ६४९) इति समासः।

७५९। नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या। ६। ३। ७५। 'पाद्' इति शत्रन्तः। 'वेदाः' इत्यसुन्नन्तः। न सत्या असत्याः। न असत्या नासत्याः। न मुञ्चतीति नमुचिः। न कुलमस्य। न खमस्य। न स्त्री पुमान्। स्त्रीपुंसयोः पुंसकभावो निपातनात्। न क्षरतीति नक्षत्रम्। क्षीयतेः क्षरतेर्वा क्षत्रमिति निपात्यते। न क्रामतीति नक्रः। 'क्रमेर्डः' न अकमस्मिन्निति नाकः।

७६०। नगोऽप्राणिष्वन्यतरस्याम्। ६। ३। ७७। नग इत्यत्र नञ्प्रकृत्या वा। नगाः–अगाः पर्वताः। 'अप्राणिषु' इति किम्। अगो वृषलः शीतेन। 'नित्यं क्रीडा–' (सू ७११) इत्यतः 'नित्यम्' इत्यनुवर्तमाने।

७६१। कुगतिप्रादयः। २। २। १८। एते समर्थेन नित्यं समस्यन्ते। कुत्सितः पुरुषः कुपुरुषः। 'गतिश्च' (सू २३) इत्यनुवर्तमाने।

७६२। ऊर्यादिच्विडाचश्च। १। ४। ६१। एते क्रियायोगे गतिसंज्ञाः स्युः। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। 'कारिकाशब्दस्योपसंख्यानम्' (वा ११३२)। कारिका क्रिया। कारिकाकृत्य।

७६३। अनुकरणं चानितिपरम्। १। ४। ६२। खाट्कृत्य। 'अनितिपरम्' किम्। खाडिति कृत्वा निरष्ठीवत्।

७६४। आदरानादरयोः सदसती। १। ४। ६३। सत्कृत्य। असत्कृत्य।

७६५। भूषणेऽलम्। १। ४। ६४। अलंकृत्य। 'भूषणे' किम्। अलं कृत्वौदनं गतः। पर्याप्तमित्यर्थः। 'अनुकरणम्–' (सू ७६३) इत्यादि त्रिसूत्री स्वभावात्कृञ्विषया।

७६६ । अन्तरपरिग्रहे । १ । ४ । ६५ । अन्तर्हत्य । मध्ये हत्वेत्यर्थः । 'अपरि
किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ।

७६७ । कणेमनसी श्रद्धाप्रतीघाते । १ । ४ । ६६ । कणेहत्य पयः पिब
मनोहत्य । 'कणे'शब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तेते । 'मनः
शब्दोऽप्यत्रैव ।

७६८ । पुरोऽव्ययम् । १ । ४ । ६७ । पुरस्कृत्य ।

७६९ । अस्तं च । १ । ४ । ६८ । अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । अस्तंग

७७० । अच्छ गत्यर्थवदेषु । १ । ४ । ६९ । 'अव्ययम्' इत्येव । अच्छगत्य
अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । 'अव्ययम्' किम् । जलमच्छं गच्छति ।

७७१ । अदोऽनुपदेशे । १ । ४ । ७० । अदःकृत्यादः कृतम् । परं प्रत्युपदेशे प्र
हरणम् । अदः कृत्वा अदः कुरु ।

७७२ । तिरोऽन्तर्धौ । १ । ४ । ७१ । तिरोभूय ।

७७३ । विभाषा कृञि । १ । ४ । ७२ । तिरस्कृत्य-तिरःकृत्य-तिरः कृत्वा ।

७७४ । उपाजेऽन्वाजे । १ । ४ । ७३ । एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृ
उपाजे कृत्वा । अन्वाजेकृत्य-अन्वाजे कृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ।

७७५ । साक्षात्प्रभृतीनि च । १ । ४ । ७४ । कृञि वा गतिसंज्ञानि स्युः । 'च्व्यर्थ
वाच्यम्' (वा ११४२) । साक्षात्कृत्य-साक्षात्कृत्वा । लवणंकृत्य-लवणं कृत्वा । मा
निपातनात् ।

७७६ । अनत्याधान उरसिमनसी । १ । ४ । ७५ । उरसिकृत्य-उरसि कृत्वा । अ
पगम्येत्यर्थः । मनसिकृत्य-मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र
उरसि कृत्वा पाणिं शेते ।

७७७ । मध्येपदेनिवचने च । १ । ४ । ७६ । एते कृञि वा गतिसंज्ञाः स्युरनत्या
मध्येकृत्य-मध्ये कृत्वा । पदेकृत्य-पदे कृत्वा । निवचनेकृत्य-निवचने कृत्वा ।
नियम्येत्यर्थः ।

७७८ । नित्यं हस्तेपाणावुपयमने । १ । ४ । ७७ । कृञि । उपयमनं विवा
'स्वीकारमात्रम्' इत्यन्ये । हस्तेकृत्य । पाणौकृत्य ।

७७९ । प्राध्वं बन्धने । १ । ४ । ७८ । 'प्राध्वम्' इत्यव्ययम् । प्राध्वंकृत्य । ब
नानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ।

७८० । जीविकोपनिषदावौपम्ये । १ । ४ । ७९ । जीविकामिव कृत्वा-जीविका
उपनिषदमिव कृत्वा-उपनिषत्कृत्य । 'औपम्ये' किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्य
सुपुरुषः । अत्र वार्तिकानि । 'प्रादयो गताद्यर्थे प्रथमया' (वा १३३५) । प्रगत आ
प्राचार्यः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा १३३६) । अतिक्रान्तो मालामतिमा
'अवादयः क्रुष्टाद्यर्थे तृतीयया' (वा १३३७) । अवक्रुष्टः कोकिलयावकोकिलः । 'प
ग्लानाद्यर्थे चतुर्थ्या' (वा १३३८) । परिग्लानोऽध्ययनाय पर्यध्ययनः । 'निरादयः

द्यर्थे पञ्चम्या' (वा १३३९)। निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः। 'कर्मप्रवचनीयानां प्रतिषेधः' (वा १३३९)। वृक्षं प्रति।

७८१। तत्रोपपदं सप्तमीस्थम्। ३। १। ९२। सप्तम्यन्ते पदे 'कर्मणि-' (सू २९१३) इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्। तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात्।

७८२। उपपदमतिङ्। २। २। १९। उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। कुम्भं करोतीति कुम्भकारः। इह 'कुम्भअस् कार' इत्यलौकिकं प्रक्रियावाक्यम्। 'अतिङ्' किम्। मा भवान्भूत्। 'माङि लुङ्' (सू २२१९) इति सप्तमीनिर्देशान्माङुपपदम्। 'अतिङ्ग्रहणं ज्ञापयति। 'सुपा' इत्येतन्नेहानुवर्तत इति। पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते 'सुपा' इति च निवृत्तम्। तथा च 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' (प ७६) इति सिद्धम्। व्याघ्री। अश्वक्रीती। कच्छपी।

७८३। अमैवाव्ययेन। २। २। २०। अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते। स्वादुंकारम्। नेह। 'कालसमयवेलासु तुमुन्' (सू ३१७९)। कालः समयो वेला वा भोक्तुम्। 'अमैव' इति किम्। अग्रे भोजम्-अग्रे भुक्त्वा। 'विभाषाग्रेप्रथमपूर्वेषु' (सू ३३४५) इति क्त्वाणमुलौ। अमा चान्येन च तुल्यविधानमेतत्।

७८४। तृतीयाप्रभृतीन्यन्यतरस्याम्। २। २। २१। 'उपदंशस्तृतीयायाम्' (सू ३३६८) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते। मूलकेनोपदंशं भुङ्क्ते-मूलकोपदंशम्।

७८५। क्त्वा च। २। २। २२। तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते। उच्चैःकृत्य-उच्चैः कृत्वा। 'अव्ययेऽयथाभिप्रेत-' (सू ३३८१) इति क्त्वा। 'तृतीयाप्रभृतीनि' इति किम्। अलं कृत्वा। खलु कृत्वा।

७८६। तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः। ५। ४। ८६। संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच्स्यात्। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु। निर्गतमङ्गुलिभ्यो निरङ्गुलम्।

७८७। अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः। ५। ४। ८७। एभ्यो रात्रेरच्स्यात्संख्याव्ययादेः। 'अहर्ग्रहणं द्वन्द्वार्थम्' (वा ३३५३)। अहश्च रात्रिश्चाहोरात्रः। सर्वा रात्रिः सर्वरात्रः। पूर्वं रात्रेः पूर्वरात्रः। संख्यातरात्रः। पुण्यरात्रः। द्वयो रात्र्योः समाहारो द्विरात्रम्। अतिक्रान्तो रात्रिमतिरात्रः।

७८८। राजाहःसखिभ्यष्टच्। ५। ४। ९१। एतदन्तात्तत्पुरुषाट्टच्स्यात्। परमराजः। अतिराजी। कृष्णसखः।

७८९। अह्नष्टखोरेव। ६। ४। १४५। एतयोरेव परतोऽह्नष्टिलोपः स्यान्नान्यत्र। उत्तमाहः। द्वे अहनी भृतो द्व्यहीनः क्रतुः। तद्धितार्थे द्विगुः। 'तमधीष्टः-' (सू १७४४) इत्यधिकारे 'द्विगोर्वा' इत्यनुवृत्तौ 'रात्र्यहःसंवत्सराच्च' (सू १७५१) इति खः। लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह। मद्राणां राज्ञी मद्रराज्ञी।

७९० । अह्नोऽह्न एतेभ्यः । ५ । ४ । ८८ । सर्वादिभ्यः परस्याहन्शब्दस्याह्नादेशः स्
त्समासान्ते परे ।

७९१ । अह्नोऽदन्तात् । ८ । ४ । ७ । अदन्तपूर्वपदस्थाद्रेफात्परस्याह्नोऽह्नादेशस्य
णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः । 'कालाट्ठञ्' (सू १३८
'द्विगोर्लुगनपत्ये' (सू १०८०) इति ठञो लुक् । द्व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । द्व्यह्ना । द्व्य
प्रियः । अत्यह्नः ।

७९२ । क्षुभ्नादिषु च । ८ । ४ । ३९ । एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् ।
चैतदर्थमह्न इत्यदन्तानुकरणे क्लेशो न कर्तव्यः । 'प्रातिपदिकान्त–' (सू १०५५) इति
वारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । 'अतः' इति तपरकरणान्नेह । परागतमहः पराह्नः

७९३ । न संख्यादेः समाहारे । ५ । ४ । ८९ । समाहारे वर्तमानस्य संख्यादेरह्नो
न स्यात् । 'संख्यादेः' इति स्पष्टार्थम् । द्वयोरह्नोः समाहारो द्व्यहः । त्र्यहः ।

७९४ । उत्तमैकाभ्यां च । ५ । ४ । ९० । आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्य
पुण्यशब्दमाह । 'पुण्यैकाभ्याम्' इत्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदि
शब्दः प्रशस्तवाची । एकाहः । 'उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थम्' इत्येके । संख्याताह

७९५ । अश्वाख्यायामुरसः । ५ । ४ । ९३ । टच्स्यात् । अश्वानामुर इवाश्वोरसं
मुख्योऽश्व इत्यर्थः ।

७९६ । अनोश्मायःसरसां जातिसंज्ञयोः । ५ । ४ । ९४ । टच्स्याज्जातौ संज्ञ
च । उपानसम् । अमृताश्मः । कालायसम् । 'मण्डूकसरसम्' इति जातिः । महानस
पिण्डाश्मः । लोहितायसम् । 'जलसरसम्' इति संज्ञा ।

७९७ । ग्रामकौटाभ्यां च तक्ष्णः । ५ । ४ । ९५ । ग्रामस्य तक्षा ग्रामतक्षः । सा
रण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः । स चासौ तक्षा च कौटतक्षः ।

७९८ । अतेः शुनः । ५ । ४ । ९६ । अतिश्वो वराहः । अतिश्वी सेना ।

७९९ । उपमानादप्राणिषु । ५ । ४ । ९७ । अप्राणिविषयकोपमानवाचिनः शुन
च्स्यात् । आकर्षः श्वेवाकर्षश्वः । 'अप्राणिषु' किम् । वानरः श्वेव वानरश्वा ।

८०० । उत्तरमृगपूर्वाच्च सक्थ्नः । ५ । ४ । ९८ । चादुपमानात् । उत्तरसक्थ
मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ।

८०१ । नावो द्विगोः । ५ । ४ । ९९ । नौशब्दान्ताद्द्विगोष्टच्स्यात्, न तु तद्धितलु
द्वाभ्यां नौभ्यामागतो द्विनावरूप्यः । 'द्विगोर्लुगनपत्ये' (सू १०८०) इत्यत्र 'अचि' इत्य
पकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । 'अतद्धितलुकि' इति कि
पञ्चभिर्नौभिः क्रीतः पञ्चनौः ।

८०२ । अर्धाच्च । ५ । ४ । १०० । अर्धान्नावष्टच्स्यात् । नावोऽर्धम्–अर्धनाव
क्लीबत्वं लोकात् ।

८०३ । खार्याः प्राचाम् । ५ । ४ । १०१ । द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखार
द्विखारि । अर्धखारम्–अर्धखारि ।

---

१ मण्डूकप्लुत्या 'अतद्धितलुकि' इत्यनुवर्तत इति शेखरकृत् ।

८०४ । द्वित्रिभ्यामञ्जलेः । ५ । ४ । १०२ । टज्वा स्याद्द्विगौ । द्व्यञ्जलम् । द्व्यञ्जलि 'अतद्धितलुकि' इत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः ।

८०५ । ब्रह्मणो जानपदाख्यायाम् । ५ । ४ । १०४ । ब्रह्मान्तात्तत्पुरुषाट्टच्स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ।

८०६ । कुमहद्भ्यामन्यतरस्याम् । ५ । ४ । १०५ । आभ्यां ब्रह्मणो वा टच्स्यात्तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः–कुब्रह्मा ।

८०७ । आन्महतः समानाधिकरणजातीययोः । ६ । ३ । ४६ । महत आकारोऽन्तादेशः स्यात्समानाधिकरण उत्तरपदे जातीये च परे । महाब्रह्मः–महाब्रह्मा । महादेवः । महाजातीयः । 'समानाधिकरणे' किम् । महतः सेवा–महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः 'सन्महत्–' (सू ७४०) इति समासो ग्रहीष्यत इति चेत् 'महाबाहुः' न स्यात् । तस्मात् 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य' (प ११४) इति परिभाषा नेह प्रवर्तते समानाधिकरणग्रहणसामर्थ्यात् । 'आत्' इति योगविभागादात्त्वं 'प्रागेकादशभ्यः–'(सू१९९५) इति निर्देशाद्वा । एकादश । महतीशब्दस्य 'पुंवत्कर्मधारय–' (सू ७४६) इति पुंवद्भावे कृत आत्त्वम् । महाजातीया । 'महदात्त्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च' (वा ३९५०) । असमानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः । 'अष्टनः कपाले हविषि' (वा ३९५१) । अष्टाकपालः । 'गवि च युक्ते' (वा ३९५२) । गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्त्वं स्यात् । अष्टागवं शकटम् । 'अच्प्रत्यन्वव–' (सू ९४३) इत्यत्र 'अच्' इति योगविभागाद्बहुव्रीहावप्यच् । अष्टानां गवां समाहारोऽष्टगवम् ' तद्युक्तत्वाच्छकटमष्टागवमिति वा ।

८०८ । द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । ६ । ३ । ४७ । आत्स्यात् । द्वौ च दश च द्वादश । अधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । 'अबहुव्रीह्यशीत्योः' किम् । द्वित्राः । द्व्यशीतिः । 'प्राक्शताद्वक्तव्यम्' (वा ३९५३) । नेह । द्विशतम् । द्विसहस्रम् ।

८०९ । त्रेस्त्रयः । ६ । ३ । ४८ । त्रिशब्दस्य 'त्रयस्' स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु । त्रिर्दश–त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । 'प्राक्शतात्' इत्येव । त्रिशतम् । त्रिसहस्रम् ।

८१० । विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । ६ । ३ । ४९ । द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत्–द्वाचत्वारिंशत् । अष्टचत्वारिंशत्–अष्टाचत्वारिंशत् - त्रिचत्वारिंशत्–त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ।

८११ । एकादिश्चैकस्य चादुक् । ६ । ३ । ७६ । एकादिर्नञ्प्रकृत्या स्यादेकस्य चादुगागमश्च । नञो विंशत्या समासे कृत एकशब्देन सह 'तृतीया' इति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन न विंशतिः एकान्नविंशतिः–एकाद्नविंशतिः । एकोनविंशतिरित्यर्थः । 'षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम्' (वा ४००१–४००२) । षोडन्–षोडश–षोढा–षड्धा ।

८१२ । परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः । २ । ४ । २६ । एतयोः परपदस्येव लिङ्गं स्यात् ।

कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । 'द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्र॰ षेधो वाच्यः' (वा १५४५) । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्रा॰ जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापका॰ मासः । निष्कौशाम्बिः ।

८१३ । पूर्ववदश्ववडवौ । २ । ४ । २७ । द्विवचनमतन्त्रम् । अश्ववडवौ । अश्व॰ तान् । अश्ववडवैः ।

८१४ । रात्राह्नाहाः पुंसि । २ । ४ । २९ । एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्॰ त्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभा॰ पूर्वरात्रः । पूर्वाह्णः । द्व्यहः । 'संख्यापूर्वं रात्रं क्लीबम्' (लि १३१) । द्विरात्रम् । त्रिरात्रम् गणरात्रम् ।

८१५ । अपथं नपुंसकम् । २ । ४ । ३० । 'तत्पुरुषः' इत्येव । अन्यत्र तु । अप॰ देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ।

८१६ । अर्धर्चाः पुंसि च । २ । ४ । ३१ । अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्यु॰ अर्धर्चः-अर्धर्चम् । ध्वजः-ध्वजम् । एवं तीर्थशरीरमण्डपीयूषदेहाङ्कुशकलशेत्यादि ।

८१७ । जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् । १ । २ । ५८ । एको॰ ऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः-ब्राह्मणः पूज्यः ।

८१८ । अस्मदो द्वयोश्च । १ । २ । ५९ । एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवच॰ वा स्यात् । वयं ब्रूमः । पक्षेऽहं ब्रवीमि । 'आवां ब्रूवः' इति वा । 'सविशेषणस्य प्रतिषे॰ (वा ७२१) । पटुरहं ब्रवीमि ।

८१९ । फल्गुनीप्रोष्ठपदानां च नक्षत्रे । १ । २ । ६० । द्वित्वे बहुत्वप्रयुक्तं कार्यं स्यात् । पूर्वे फल्गुन्यौ-पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे-पूर्वाः प्रोष्ठपदाः । 'नक्षत्रे' किम् । फल्गुन्यौ माणविके ।

८२० । तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् । १ । २ । ६॰ बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । 'तिष्य-' इति किम् । विशाखा॰ राधाः । 'नक्षत्र-' इति किम् । तिष्यपुनर्वसवो माणवकाः ।

८२१ । स नपुंसकम् । २ । ४ । १७ । समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । परव॰ ङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' (वा १५५६ पञ्चमूली । 'आबन्तो वा' (वा १५५७) । पञ्चखट्वी-पञ्चखट्वम् । 'अनो नलोपश्च वा च द्वि॰ स्त्रियाम्' (वा १५५८) । पञ्चतक्षी-पञ्चतक्षम् । 'पात्राद्यन्तस्य न' (वा १५५९ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । 'पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा' (वा १५६॰ पुण्याहम् । सुदिनाहम् । 'पथः संख्याव्ययादेः' (वा १५५४) । संख्याव्ययादेः॰ कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः प॰ विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः । 'सामान्ये नपुंसक॰ (वा ५०४३) । मृदु पचति । प्रातः कमनीयम् ।

८२२ । तत्पुरुषोऽनञ्कर्मधारयः । २ । ४ । १९ । अधिकारोऽयम्

८२३ । संज्ञायां कन्थोशीनरेषु । २ । ४ । २० । कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः । तेषां कन्था सौशमिकन्थम् । 'संज्ञायाम्' किम् । वीरणकन्था । 'उशीनरेषु' किम् । दाक्षिकन्था ।

८२४ । उपज्ञोपक्रमं तदाद्याचिख्यासायाम् । २ । ४ । २१ । उपज्ञान्त उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात्, तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यामिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः ।

८२५ । छाया बाहुल्ये । २ । ४ । २२ । छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । 'विभाषा सेना–' (सू ८२८) इति विकल्पस्यायमपवादः । 'इक्षुच्छायानिषादिन्यः' इति तु 'आ समन्तान्निषादिन्यः' इत्याङ्श्लेषो बोध्यः ।

८२६ । सभा राजामनुष्यपूर्वा । २ । ४ । २३ । राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् । 'पर्यायस्यैवेष्यते' (वा ५१९) । नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह । रक्षःसभम् । पिशाचसभम् ।

८२७ । अशाला च । २ । ४ । २४ । संघातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । 'अशाला' किम् । धर्मसभा । धर्मशालेत्यर्थः ।

८२८ । विभाषा सेनासुराच्छायाशालानिशानाम् । २ । ४ । २५ । एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम्–ब्राह्मणसेना । यवसुरम्–यवसुरा । कुड्यच्छायम्–कुड्यच्छाया । गोशालम्–गोशाला । श्वनिशम्–श्वनिशा । 'तत्पुरुषोऽनञ्कर्मधारयः' (सू ८२२) इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना ।

इति तत्पुरुषसमासप्रकरणम् ।

अथ बहुव्रीहिसमासप्रकरणम् ।

८२९ । शेषो बहुव्रीहिः । २ । २ । २३ । अधिकारोऽयम् । 'द्वितीया श्रित–' (सू ६८६) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ।

८३० । अनेकमन्यपदार्थे । २ । २ । २४ । अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः' (वा १३६०) । प्रपतितपर्णः प्रपर्णः । 'नञोऽस्त्यर्थानां वा वाच्योत्तरपदलोपः' (वा १३६१) । अविद्यमानपुत्रोऽपुत्रः । 'अस्ति' इति विभक्तिप्रतिरूपकमव्ययम । अस्तिक्षीरा गौः ।

---

१ इदं च युक्तिसिद्धम् । नियतलिङ्गत्वाभावे विशेष्यविशेषासंनिधाने च सर्वलिङ्गवाचकस्य 'नपुंसकं लिङ्गं सर्वनाम' इति 'दाण्डिनायन–' (६ । ४ । १७४) सूत्रभाष्ये न्याय्यत्वेन दर्शितत्वात् ।

८३१। स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु। ६।३।३४। भाषितपुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुव्रीहिर्निपातनात्पञ्चम्या अलुक्। षष्ठ्याश्च लुक्। तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो य… तथाभूतस्य स्त्रीवाचकस्य शब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्त… रपदे न तु पूरण्यां प्रियादौ च परतः। 'गोस्त्रियोः—' (सू ६५६) इति ह्रस्वः। चित्रा गावो यस्येति लौकिकविग्रहे। 'चित्राअस्' 'गोअस्' इत्यलौकिकविग्रहे। चित्रगुः। रूपव… द्भार्यः। चित्रा जरती गौर्यस्येति विग्रहेऽनेकोक्तेर्बहूनामपि बहुव्रीहिः। अत्र केचित्… चित्राजरतीगुः—जरतीचित्रगुर्वा। एवं दीर्घातन्वीजङ्घः—तन्वीदीर्घाजङ्घः। त्रिपदे बहु… व्रीहौ प्रथमं न पुंवत्। उत्तरपदस्य मध्यमेन व्यवधानात्। द्वितीयमपि न पुंवत्। पूर्वप… त्वाभावात्। 'उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः। पूर्वपदशब्दस्तु प्र… मावयवे' इति वदन्ति। वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते। 'आनङ् ऋतः—' (सू ९…) इत्यत्र यथा। तेनोपान्त्यस्य पुंवदेव। 'चित्राजरद्गुः' इत्यादि। अत एव 'चित्राजर… गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुः' इति[1] भाष्यम्। कर्मधारयपूर्वपदे तु द्वयो… पुंवत्। जरच्चित्रगुः। कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः। 'स्त्रियाः' किम्… ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः। 'भाषितपुंस्कात्' किम्। गङ्गाभार्यः। 'अनू… किम्। वामोरूभार्यः। 'समानाधिकरणे' किम्। कल्याण्या माता कल्याणीमाता… 'स्त्रियाम्' किम्। कल्याणी प्रधानं यस्य स कल्याणीप्रधानः। पूरण्यां तु।

८३२। अप्पूरणीप्रमाण्योः। ५।४।११६। पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं त… न्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप्स्यात्। कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्च… रात्रयः। स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः। 'पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्या… (वा ३३६९,३९१०)। रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या। अन्यत्र तु।

८३३। नद्यृतश्च। ५।४।१५३। नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः क… स्यात्। पुंवद्भावः।

८३४। केऽणः। ७।४।१३। के परेऽणो ह्रस्वः स्यात्। इति प्राप्ते।

८३५। न कपि। ७।४।१४। कपि परे ह्रस्वो न स्यात्। कल्याणपञ्चमी… पक्षः। अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम्। बहुकर्तृक… 'अप्रियादिषु' किम्। कल्याणीप्रियः। प्रिया। मनोज्ञा। कल्याणी। सुभगा। दुर्भगा… भक्तिः। सचिवा। स्वसा। कान्ता। क्षान्ता। समा। चपला। दुहिता। वामा। अबला… तनया। 'सामान्ये नपुंसकम्'। दृढं भक्तिर्यस्य स दृढभक्तिः। स्त्रीत्वविवक्षा… तु दृढाभक्तिः।

८३६। तसिलादिष्वा कृत्वसुचः। ६।३।३५। तसिलादिष्वाकृत्वसुजन्ते… परेषु स्त्रियाः पुंवत्स्यात्। परिगणनं कर्तव्यम्। अव्याप्त्यतिव्याप्तिपरिहाराय। 'त्रत… (वा ३९१८)। 'तरतमपौ' (वा ३९१९)। 'चरड्जातीयरौ' (वा ३९२०)। 'कल्पाद्यु…

१ भाष्ये तु प्रकृतसूत्रे 'पट्वीमृदुभार्यः' इत्युपलभ्यते। तथा च 'इति' इत्यस्याग्रे 'प्रयो… सूचयति' इति शेषः पूरणीयः।

देशीयरौ' (वा ३९२१)। 'रूपप्पाशपौ' (वा ३९२२)। 'थाल्' (वा ३९२३)। 'तिल्थ्यनौ' (वा ३९२५)। बह्वीषु बहुत्र—बहुतः। दर्शनीयतरा। दर्शनीयतमा। 'घरूप—' (सू ९८९) इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते। पट्वितरा। पट्वितमा। पटुचरी। पटुजातीया। दर्शनीयकल्पा। दर्शनीयदेशीया। दर्शनीयरूपा। दर्शनीयपाशा। बहुथा। प्रशस्ता वृकी वृकतिः। अजाभ्यो हिता अजथ्या। 'शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः' (वा ३९२६)। बह्वीभ्यो देहि बहुशः। अल्पाभ्यो देहि अल्पशः। 'त्वतलोर्गुणवचनस्य' (वा ३९२७)। शुक्लाया भावः शुक्लत्वम्। 'गुणवचनस्य' किम्। कर्त्र्या भावः कर्त्रीत्वम्। 'शरदः कृतार्थता' इत्यादौ तु सामान्ये नपुंसकम्। 'भस्याढे तद्धिते' (वा ३९२८)। हस्तिनीनां समूहो हास्तिकम्। 'अढे' किम्। रौहिणेयः। 'स्त्रीभ्यो ढक्' (सू ११२३) इति ढोऽत्र गृह्यते। 'अग्नेर्ढक्' (सू १२३६)। इति ढकि तु पुंवदेव। अग्नायी देवतास्य स्थालीपाकस्याग्नेयः। सपत्नीशब्दस्त्रिधा। शत्रुपर्यायात्सपत्नशब्दाच्छार्ङ्गरवादित्वान्ङीन्येकः। समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः। स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः। आद्ययोः शिवाद्यण्। सपत्न्या अपत्यं सापत्नः। तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव। न त्वण्। शिवादौ रूढयोरेव ग्रहणात्सापत्यः। 'ठक्छसोश्च' (वा ३९२९)। भवत्याश्छात्रा भावत्काः। भवदीयाः। एतद्वार्तिकम् 'एकतद्धिते च' (सू १०००) इति सूत्रं च न कर्तव्यम्[1]। 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति भाष्यकारेष्ट्या गतार्थत्वात्। सर्वकाम्यति। सर्विका भार्या यस्य सर्वकभार्यः। सर्वप्रिय इत्यादि। पूर्वस्यैवेदम्। 'भस्त्रैषाजाज्ञाद्वा—' (सू ४६६) इति लिङ्गात्। तेनाकच्येकशेषवृत्तौ च न। सर्विका। सर्वाः। 'कुक्कुट्यादीनामण्डादिषु' (वा ३९३४)। कुक्कुट्या अण्डं कुक्कुटाण्डम्। मृग्याः पदं मृगपदम्। मृगक्षीरम्। काकशावः।

८३७। क्यङ्मानिनोश्च। ६। ३। ३६। एतयोः परतः पुंवत्। एनीवाचरत्येतायते। श्येनीवाचरति श्येतायते। स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनीयमानिनी। दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः।

८३८। न कोपधायाः। ६। ३। ३७। कोपधायाः स्त्रिया न पुंवत्। पाचिकाभार्यः। रसिकाभार्यः। मद्रिकायते। मद्रिकामानिनी। 'कोपधप्रतिषेधे तद्धितवुग्रहणम्' (वा ३९३१)। नेह। पाका भार्या यस्य स पाकभार्यः।

८३९। संज्ञापूरण्योश्च। ६। ३। ३८। अनयोर्न पुंवत्। दत्ताभार्यः। दत्तामानिनी। दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति। पञ्चमीभार्यः। पञ्चमीपाशा।

८४०। वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे। ६। ३। ३९। वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत्। स्रौघ्नीभार्यः। माथुरीयते। माथुरीमानिनी। 'वृद्धिनिमित्तस्य' किम्। मध्यमभार्यः। 'तद्धितस्य' किम्। काण्डलावभार्यः। 'वृद्धि'शब्देन किम्। तावद्भार्यः। रक्ते तु काषायी कन्था यस्य

---

१ अष्टाध्याय्यामपाठात्, अन्यवार्तिकानामिवात्र प्रकरणे पाठाभावादिति भावः।

स काषायकन्थः। विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः। वृद्धिशब्देन वृद्धिं
फलोपधानाभावादिह पुंवत्। वैयाकरणभार्यः। सौवश्वभार्यः।

८४१। स्वाङ्गाच्चेतः। ६।३।४०। स्वाङ्गाद्य ईकारस्तदन्ता स्त्री न पुंवत्। सुके
भार्यः। 'स्वाङ्गात्' किम्। पटुभार्यः। 'ईतः' किम्। अकेशभार्यः। 'अमानिनि
वक्तव्यम्' (वा ३९३२)। सुकेशमानिनी।

८४२। जातेश्च। ६।३।४१। जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत्। शू
भार्यः। ब्राह्मणीभार्यः। सौत्रस्यैवायं निषेधः। तेन हस्तिनीनां समूहो हास्तिकमि
'भस्याढे–' (वा ३९२८) इति तु भवत्येव।

८४३। संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये। २।२।२५। संख्येया
संख्ययाव्ययादयः समस्यन्ते स बहुव्रीहिः। दशानां समीपे ये सन्ति त उपदशाः।
एकादश वेत्यर्थः। 'बहुव्रीहौ संख्येये–' (सू ८९१) इति वक्ष्यमाणो डच्।

८४४। ति विंशतेर्डिति। ६।४।१४२। विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डि
आसन्नविंशाः। विंशतेरासन्ना इत्यर्थः। अदूरत्रिंशाः। अधिकचत्वारिंशाः। द्वौ वा त्रये
द्वित्राः। द्विरावृत्ता दश द्विदशाः। विंशतिरित्यर्थः।

८४५। दिङ्नामान्यन्तराले। २।२।२६। दिशो नामान्यन्तराले वाच्ये प्राग्व
दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा। नामग्रहणाद्यौगिकानां न। ऐन्द्र
कौबेर्याश्चान्तरालं दिक्।

८४६। तत्र तेनेदमिति सरूपे। २।२।२७। सप्तम्यन्ते ग्रहणविषये सरूपे
तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स
व्रीहिः। 'इति'शब्दादयं विषयविशेषो लभ्यते। इच्समासान्तो वक्ष्यते। तिष्ठद्गुप्रभृतिषु
त्ययस्य पाठादव्ययीभावत्वमव्ययत्वं च। 'अन्येषामपि दृश्यते' (सू ३५३९) इति दीर्घः
केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि। दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं द
दाण्डि। मुष्टीमुष्टि।

८४७। ओर्गुणः। ६।४।१४६। उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते। अवादे
बाहूबाहवि। 'ओरोत्' इति वक्तव्ये गुणोक्तिः 'संज्ञापूर्वको विधिरनित्यः' (प ९
इति ज्ञापयितुम्। तेन 'स्वायंभुवम्' इत्यादि सिद्धम्। 'सरूपे' इति किम्। हलेन मुसले

८४८। तेन सहेति तुल्ययोगे। २।२।२८। तुल्ययोगे वर्तमानं 'सह' इत्येत
तीयान्तेन प्राग्वत्।

८४९। वोपसर्जनस्य। ६।३।८२। बहुव्रीह्यवयवस्य सहस्य सः स्याद्वा। पुत्रेण
सपुत्रः सहपुत्रो वागतः। 'तुल्ययोगवचनं प्रायिकम्'। सकर्मकः। सलोमकः।

८५०। प्रकृत्याशिषि। ६।३।८३। सहशब्दः प्रकृत्या स्यादाशिषि। स्वस्ति
सहपुत्राय सहामात्याय। 'अगोवत्सहलेष्विति वाच्यम्' (वा ३९९०)। सगवे। सवत्स
सहलाय।

८५१। बहुव्रीहौ संख्येये डजबहुगणात्। ५।४।७३। संख्येये यो बहु
स्तस्माड्डच्स्यात्। उपदशाः। 'अबहुगणात्' किम्। उपबहवः। उपगणाः। अत्र

विशेषः। 'संख्यायास्तत्पुरुषस्य वाच्यः' (वा ३३४८)। निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य। निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः।

८९२। बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्। ५।४।११३। व्यत्ययेन षष्ठी। स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच्स्यात्। दीर्घे सक्थिनी यस्य स दीर्घसक्थः। जलजाक्षी। 'स्वाङ्गात्' किम्। दीर्घसक्थि शकटम्। स्थूलाक्षा वेणुयष्टिः। 'अक्ष्णोऽदर्शनात्' (सू ९४४) इत्यच्।

८९३। अङ्गुलेर्दारुणि। ५।४।११४। अङ्गुल्यन्ताद्बहुव्रीहेः षच्स्याद्दारुण्यर्थे। पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु। अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्ठमुच्यते। 'बहुव्रीहिः' किम्। द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः। तद्धितार्थे तत्पुरुषे 'तत्पुरुषस्याङ्गुलेः–' (सू ७८६) इत्यच्। 'दारुणि' किम्। पञ्चाङ्गुलिर्हस्तः।

८९४। द्वित्रिभ्यां ष मूर्ध्नः। ५।४।११५। आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः। 'नेतुर्नक्षत्रे अब्वक्तव्यः' (वा ३३६०)। मृगो नेता यासां ता मृगनेत्रा रात्रयः। पुष्यनेत्राः।

८९५। अन्तर्बहिर्भ्यां च लोम्नः। ५।४।११७। आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ। अन्तर्लोमः। बहिर्लोमः।

८९६। अञ्नासिकायाः संज्ञायां नसं चास्थूलात्। ५।४।११८। नासिकान्ताद्बहुव्रीहेरच्स्यान्नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात्।

८९७। पूर्वपदात्संज्ञायामगः। ८।४।३। पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने। द्रुरिव नासिकास्य द्रुणसः। खरणसः। 'अगः' किम्। ऋचामयनमृगयनम्। 'अणृगयनादिभ्यः' (सू १४९२) इति निपातनाण्णत्वाभावमाश्रित्य 'अगः' इति प्रत्याख्यातं भाष्ये। 'अस्थूलात्' किम्। स्थूलनासिकः। 'खुरखराभ्यां वा नस्'[१] (वा ३३६३)। खुरणाः। खरणाः। 'पक्षेऽजपीष्यते'। खुरणसः। खरणसः।

८९८। उपसर्गाच्च। ५।४।११९। प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच्नासिकाया नसादेशश्च। असंज्ञार्थं वचनम्। उन्नता नासिका यस्य स उन्नसः। 'उपसर्गादनोत्परः' इति सूत्रं तद्भङ्क्त्वा भाष्यकार आह।

८९९। उपसर्गाद्बहुलम्। ८।४।२८। उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम्। प्रणसः। 'वेर्ग्रो वक्तव्यः' (वा ३३६५)। विगता नासिकास्य विग्रः। 'ख्यश्च' (वा ३३६६)। विख्यः। कथं तर्हि 'विनसा हतबान्धवा' इति भट्टिः। विगतया नासिकयोपलक्षितेति व्याख्येयम्।

९००। सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः। ५।४।१२०। एते बहुव्रीहयोऽच्प्रत्ययान्ता निपात्यन्ते। शोभनं प्रातरस्य सुप्रातः। शोभनं श्वोऽस्य

---

१ वार्तिके वाग्रहणं 'पक्षेऽजपि' 'खुरणसः' इत्युदाहरणं च निर्मूलम्। मुनित्रयानुक्तत्वात्–इति रत्नाकरः।

सुभ्रः। शोभनं दिवास्य सुदिवः। शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रोऽश्रयोऽस्य चतुरश्रः। एण्या इव पादावस्यैणीपदः। अजपदः। प्रोष्ठौ गौस्तस्येव पादावस्य प्रोष्ठपदः।

८६१। नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्। ५। ४। १२१। अच्स्यात्। अहलः-अहलिः। असक्थः-असक्थिः। एवं दुःसुभ्याम्। 'शक्त्योः' इति पाठान्तरम्। अशक्तः-अशक्तिः।

८६२। नित्यमसिच्प्रजामेधयोः। ५। ४। १२२। 'नञ्दुःसुभ्यः' इत्येव। अप्रजाः। दुष्प्रजाः। सुप्रजाः। अमेधाः। दुर्मेधाः। सुमेधाः।

८६३। धर्मादनिच्केवलात्। ५। ४। १२४। केवलात्पूर्वपदात्परो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच्स्यात्। कल्याणधर्मा। 'केवलात्' किम्। परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत्। स्वशब्दो हीह न केवलं पूर्वपदं किं तु मध्यमत्वादापेक्षिकः। 'संदिग्धसाध्यधर्मा' इत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः। एवं तु 'परमस्वधर्मा' इत्यपि साध्वेव। 'निवृत्तिधर्मा' 'अनुच्छित्तिधर्मा' इत्यादिवत्। पूर्वपदं तु बहुव्रीहिणाक्षिप्यते।

८६४। जम्भा सुहरिततृणसोमेभ्यः। ५। ४। १२५। 'जम्भा' इति कृतसमासान्तं निपात्यते। 'जम्भो भक्ष्ये दन्ते च'। शोभनो जम्भोऽस्य सुजम्भा। हरितजम्भा। तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा। सोमजम्भा। 'स्वादिभ्यः' किम्। पतितजम्भः।

८६५। दक्षिणेर्मा लुब्धयोगे। ५। ४। १२६। दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः। व्याधेन कृतव्रण इत्यर्थः।

८६६। इच्कर्मव्यतिहारे। ५। ४। १२७। कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच्स्यात्। मासान्तः। केशाकेशि। मुसलामुसलि।

८६७। द्विदण्ड्यादिभ्यश्च। ५। ४। १२८। तादर्थ्ये चतुर्थ्येषा। एषां सिद्ध्यर्थमिच्प्रत्ययः स्यात्। द्वौ दण्डौ यस्मिन्प्रहरणे तद्द्विदण्डि प्रहरणम्। द्विमुसलि। उभाहस्ति। उभयाहस्ति।

८६८। प्रसंभ्यां जानुनोर्ज्ञुः। ५। ४। १२९। आभ्यां परयोर्जानुशब्दयोर्ज्ञुरादेशः स्याद्बहुव्रीहौ। प्रगते जानुनी यस्य प्रज्ञुः। संज्ञुः।

८६९। ऊर्ध्वाद्विभाषा। ५। ४। १३०। ऊर्ध्वज्ञुः-ऊर्ध्वजानुः।

८७०। धनुषश्च। ५। ४। १३२। धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात्। शार्ङ्गधन्वा।

८७१। वा संज्ञायाम्। ५। ४। १३३। शतधन्वा-शतधनुः।

८७२। जायाया निङ्। ५। ४। १३४। जायान्तस्य बहुव्रीहेर्निङादेशः स्यात्।

८७३। लोपो व्योर्वलि। ६। १। ६६। वकारयकारयोर्लोपः स्याद्वलि। पुंवद्भावः। युवतिर्जायास्य युवजानिः।

८७४। गन्धस्येदुत्पूतिसुसुरभिभ्यः। ५। ४। १३५। एभ्यो गन्धस्येकारोऽन्तादेशः स्यात्। उद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। 'गन्धस्येत्त्वे तदेकान्तग्रहणम्

(वा ३३६८) । एकान्त एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह । शोभना गन्धा द्रव्याण्यस्य सुगन्ध आपणिकः ।

८७५ । अल्पाख्यायाम् । ५ । ४ । १३६ । सूपस्य गन्धो लेशो यस्मिंस्तत्सूपगन्धि भोजनम् । घृतगन्धि । 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः' इति विश्वः ।

८७६ । उपमानाच्च । ५ । ४ । १३७ । पद्मस्येव गन्धोऽस्य पद्मगन्धिः ।

८७७ । पादस्य लोपोऽहस्त्यादिभ्यः । ५ । ४ । १३८ । हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् । 'अहस्त्यादिभ्यः' किम् । हस्तिपादः । कुसूलपादः ।

८७८ । कुम्भपदीषु च । ५ । ४ । १३९ । कुम्भपद्यादिषु पादस्य लोपो ङीप्च निपात्यते स्त्रियाम् । 'पादः पत्' (सू ४१४) । कुम्भपदी । 'स्त्रियाम्' किम् । कुम्भपादः ।

८७९ । संख्यासुपूर्वस्य । ५ । ४ । १४० । पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ।

८८० । वयसि दन्तस्य दतृ । ५ । ४ । १४१ । संख्यासुपूर्वस्य दन्तस्य 'दतृ' इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षड् दन्ता अस्य षोडन् । सुदन्–सुदती । 'वयसि' किम् । द्विदन्तः करी । सुदन्तो नटः ।

८८१ । स्त्रियां संज्ञायाम् । ५ । ४ । १४३ । दन्तस्य 'दतृ' स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । 'संज्ञायाम्' किम् । समदन्ती ।

८८२ । विभाषा श्यावारोकाभ्याम् । ५ । ४ । १४४ । दन्तस्य 'दतृ' स्याद्बहुव्रीहौ । श्यावदन्–श्यावदन्तः । अरोकदन्–अरोकदन्तः ।

८८३ । अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । ५ । ४ । १४५ । एभ्यो दन्तस्य दतृ वा कुड्मलाग्रदन्–कुड्मलाग्रदन्तः ।

८८४ । ककुदस्यावस्थायां लोपः । ५ । ४ । १४६ । अजातककुत् । पूर्णककुत् ।

८८५ । त्रिककुत्पर्वते । ५ । ४ । १४७ । त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ।

८८६ । उद्विभ्यां काकुदस्य । ५ । ४ । १४८ । लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ।

८८७ । पूर्णाद्विभाषा । ५ । ४ । १४९ । पूर्णकाकुत्–पूर्णकाकुदः ।

८८८ । सुहृद्दुर्हृदौ मित्रामित्रयोः । ५ । ४ । १५० । सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुर्हृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ।

८८९ । उरःप्रभृतिभ्यः कप् । ५ । ४ । १५१ । व्यूढोरस्कः । प्रियसर्पिष्कः । इह 'पुमान्' 'अनड्वान्' 'पयः' 'नौः' 'लक्ष्मीः' इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु 'शेषाद्विभाषा' (सू ८९१) इति विकल्पेन कप् । द्विपुमान्–द्विपुंस्कः । 'अर्थान्नञः' (ग १४९) । अनर्थकम् । 'नञः' किम् । अपार्थम्–अपार्थकम् ।

८९० । इनः स्त्रियाम् । ५ । ४ । १५२ । बहुदण्डिका नगरी । 'अनिनस्मन्ग्रहणान्यर्थ-

नता चानर्थकेनापि तदन्तविधिं प्रयोजयन्ति' (प १७)। बहुवाग्मिका। 'स्त्रियाम्' किम्। ब
दण्डी। बहुदण्डिको ग्रामः।

८९१। शेषाद्विभाषा। ५। ४। १५४। अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहु
कब्वा स्यात्। महायशस्कः-महायशाः। 'अनुक्त-' इत्यादि किम्। व्याघ्रपात्। सुगन्धि
प्रियपथः। 'शेषाधिकारस्थात्' किम्। उपबहवः। उत्तरपूर्वा। सपुत्रः। तन्त्रादिना
शब्दोऽर्थद्वयपरः।

८९२। आपोऽन्यतरस्याम्। ७। ४। १५। कप्यावन्तस्य ह्रस्वो वा स्यात्। बहु
लाकः-बहुमालकः। कबभावे बहुमालः।

८९३। न संज्ञायाम्। ५। ४। १५५। 'शेषात्-' (सू ८९१) इति प्राप्तः कब्न स्या
ज्ञायाम्। विश्वे देवा अस्य विश्वेदेवः।

८९४। ईयसश्च। ५। ४। १५६। ईयसन्तोत्तरपदान्न कप्। बहवः श्रेयांसोऽस्य ब
यान्। 'गोस्त्रियोः-' (सू ६५६) इति ह्रस्वत्वे प्राप्ते। 'ईयसो बहुव्रीहेर्नेति वाच्यम्' (वा ६
बह्वयः श्रेयस्योऽस्य बहुश्रेयसी। 'बहुव्रीहेः' किम्। अतिश्रेयसिः।

८९५। वन्दिते भ्रातुः। ५। ४। १५७। पूजितेऽर्थे यो भ्रातृशब्दस्तदन्तान्न कप्स्
प्रशस्तो भ्राता यस्य प्रशस्तभ्राता सुभ्राता। 'न पूजनात्' (सू ९५४) इति निषे
'बहुव्रीहौ सक्थ्यक्ष्णोः-' (सू ८५२) इत्यतः प्रागेवेति वक्ष्यते। 'वन्दिते' किम्। मूर्खभ्रातृ

८९६। नाडीतन्त्र्योः स्वाङ्गे। ५। ४। १५९। स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तद
त्कब्न स्यात्। बहुनाडिः कायः। बहुतन्त्रीर्ग्रीवा। बहुतन्त्रीर्धमनी। स्त्रीप्रत्ययान्तत
वा ह्रस्वो न। 'स्वाङ्गे' किम्। बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा।

८९७। निष्प्रवाणिश्च। ५। ४। १६०। कबभावोऽत्र निपात्यते। प्रपूर्वाद्वयतेर्ल्
प्रवाणी तन्तुवायशलाका। निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः। समाप्तवानः। नव इत्
८९८। सप्तमीविशेषणे बहुव्रीहौ। २। २। ३५। सप्तम्यन्तं विशेषणं बहुव्रीहौ
प्रयोज्यम्। कण्ठेकालः। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः। चित्रगुः। 'सर्व
संख्ययोरुपसंख्यानम्' (वा १४१९)। सर्वश्वेतः। द्विशुक्लः। 'मिथोऽनयोः समासे सं
पूर्वं शब्दपरविप्रतिषेधात्' (वा ५०४४)। द्व्यन्यः। 'संख्याया अल्पीयस्याः'
१४१७)। द्वित्राः। द्वन्द्वेऽपि। द्वादश। 'वा प्रियस्य' (वा १४२०)। गुडप्रियः। प्रियगु
'गड्वादेः परा सप्तमी' (वा १४२१)। गडुकण्ठः। क्वचिन्न। वहेगडुः।

८९९। निष्ठा। २। २। ३६। निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। कृतकृत्यः। 'जाति
लसुखादिभ्यः परा निष्ठा वाच्या' (वा १४२२)। सारङ्गजग्धी। मासजाता। सुखजा
'प्रायिकं चेदम्'। कृतकटः। पीतोदकः।

९००। वाहिताग्न्यादिषु। २। २। ३७। आहिताग्निः। अग्न्याहितः। आकृ
णोऽयम्। 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' (वा १४२५)। अस्युद्यतः। दण्डपा
क्वचिन्न। विवृतासिः।

इति बहुव्रीहिसमासप्रकरणम्।

अथ द्वन्द्वसमासप्रकरणम् ।

९०१ । चार्थे द्वन्द्वः । २ । २ । २९ । अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । 'परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः' । 'अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः' । 'मिलितानामन्वय इतरेतरयोगः' । 'समूहः समाहारः' । 'तत्रेश्वरं गुरुं च भजस्व' इति समुच्चये 'भिक्षामट गां चानय' इत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः ।

९०२ । राजदन्तादिषु परम् । २ । २ । ३१ । एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्तः । 'धर्मादिष्वनियमः' (वा १४१८)। अर्थधर्मौ—धर्मार्थौ । दंपती—जंपती—जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृतिगणोऽयम् ।

९०३ । द्वन्द्वे घि । २ । २ । ३२ । द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ । 'अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे (वा१४१०) । हरिगुरुहराः—हरिहरगुरवः ।

९०४ । अजाद्यदन्तम् । २ । २ । ३३ । इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । 'बहुष्वनियमः' । अश्वरथेन्द्राः । इन्द्राश्वरथाः । 'घ्यन्तादजाद्यदन्तं विप्रतिषेधेन' (वा १४२६) । इन्द्राग्नी ।

९०५ । अल्पाच्तरम् । २ । २ । ३४ । शिवकेशवौ । 'ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण' (वा १४२१) । हेमन्तशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । 'समाक्षराणाम्' किम् । ग्रीष्मवसन्तौ । 'लघ्वक्षरं पूर्वम्' (वा १४१३) । कुशकाशम् । 'अभ्यर्हितं च' (वा १४१२) । तापसपर्वतौ । 'वर्णानामानुपूर्व्येण' (वा १४१५) । ब्राह्मणक्षत्रियविट्शूद्राः । 'भ्रातुर्ज्यायसः' (वा १४१६) । युधिष्ठिरार्जुनौ ।

९०६ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । २ । ४ । २ । एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ।

९०७ । अनुवादे चरणानाम् । २ । ४ । ३ । चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे । 'स्थेणोर्लुङीति वक्तव्यम्' (वा १५३५–१५३६) । उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ।

९०८ । अध्वर्युक्रतुरनपुंसकम् । २ । ४ । ४ । यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । 'अध्वर्युक्रतुः' किम् । इषुवज्रौ सामवेदे विहितौ । 'अनपुंसकम्' किम् । राजसूयवाजपेये । अर्धर्चादी ।

९०९ । अध्ययनतोऽविप्रकृष्टाख्यानाम् । २ । ४ । ५ । अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ।

९१० । जातिरप्राणिनाम् । २ । ४ । ६ । प्राणिवर्जजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु । विट्शूद्राः । द्रव्यजातीयानामेव । नेह । रूपरसौ । गमनाकुञ्चने जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु । बदरामलकानि ।

---

१ अत्र च 'अथ यत्र संख्यासर्वनाम्नोरेव बहुव्रीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् । परत्वात्संख्यायाः' इति भाष्यं मानम् ।

९११। विशिष्टलिङ्गो नदीदेशोऽग्रामाः। २। ४। ७। ग्रामवर्जनदीदेशवाचिनां भि
लिङ्गानां समाहारे द्वन्द्व एकवत्स्यात्। उद्ध्यश्च इरावती च उद्ध्येरावति। गङ्गा च शो
गङ्गाशोणम्। कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम्। 'भिन्नलिङ्गानाम्' किम्। गङ्गायमु
मद्रकेकयाः। 'अग्रामाः' किम्। जाम्बवं नगरम्। शालूकिनी ग्रामः। जाम्बवशालूकिन्यौ
९१२। क्षुद्रजन्तवः। २। ४। ८। एषां समाहारे द्वन्द्व एकवत्स्यात्। यूकालिक्ष
आ नकुलात्क्षुद्रजन्तवः।
९१३। येषां च विरोधः शाश्वतिकः। २। ४। ९। एषां प्राग्वत्। 'अहिनकु
'गोव्याघ्रम्' 'काकोलूकम्' इत्यादौ परत्वात् 'विभाषा वृक्षमृग–' (सू ९१६) इति
चकारेण बाध्यते।
९१४। शूद्राणामनिरवसितानाम्। २। ४। १०। अबहिष्कृतानां शूद्राणां प्राक्
तक्षायस्कारम्। पात्राद्बहिष्कृतानां तु चाण्डालमृतपाः।
९१५। गवाश्वप्रभृतीनि च। २। ४। ११। यथोच्चारितानि साधूनि स्युः। गवाश्व
दासीदासमित्यादि।
९१६। विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्त
णाम्। २। ४। १२। वृक्षादीनां सतानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्व
'वृक्षादौ विशेषाणामेव ग्रहणम्' (वा ९९८)। प्लक्षन्यग्रोधम्–प्लक्षन्यग्रोधाः। रुरुपृषतम्–रु
पृषताः। कुशकाशम्–कुशकाशाः। व्रीहियवम्–व्रीहियवाः। दधिघृतम्–दधिघृते। गोम
षम्–गोमहिषाः। शुकबकम्–शुकबकाः। अश्ववडवम्–अश्ववडवौ। पूर्वापरम्–पूर्वा
अधरोत्तरम्–अधरोत्तरे। 'फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृति
द्वन्द्व एकवदिति वाच्यम्' (वा १५४०)। बदराणि चामलकानि च बदरामलकम्। जा
रप्राणिनाम्' (सू ९१०) इत्येकवद्भावः। नेह। बदरामलके। रथिकाश्वारोहौ। प्लक्षन्यग्रो
वित्यादि। 'विभाषा वृक्ष–' (सू ९१६) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं 'जातिरप्रा
नाम्' (सू ९१०) इति नित्ये प्राप्ते विकल्पार्थम्। पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्रा
'मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहेतरेतरयोग एव' इति नियम
मृगशकुनिग्रहणम्। एवं 'पूर्वापरम्' 'अधरोत्तरम्' इत्यपि। अश्ववडवग्रहणं तु पक्षे नपुंस
त्वार्थम्। अन्यथा परत्वात् 'पूर्ववदश्ववडवौ' (सू ८१३) इति स्यात्।
९१७। विप्रतिषिद्धं चानधिकरणवाचि। २। ४। १३। विरुद्धार्थानामद्रव्यवाचि
द्वन्द्व एकवद्वा स्यात्। शीतोष्णम्–शीतोष्णे। वैकल्पिकः समाहारद्वन्द्वः 'चार्थे–' (सू ९
इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम्।
द्रव्यवाचिनामितरेतरयोग एव। शीतोष्णे उदके स्तः। 'विप्रतिषिद्धम्' किम्। नन्दकपा
जन्यौ। इह पाक्षिकः समाहारद्वन्द्वो भवत्येव।
९१८। न दधिपयआदीनि। २। ४। १४। एतानि नैकवत्स्युः। दधिपयसी। इध्मा
र्हिषी। निपातनाद्दीर्घः। ऋक्सामे। वाङ्मनसे।
९१९। अधिकरणैतावत्त्वे च। २। ४। १५। द्रव्यसंख्यावगमे एकवदेवेति नियमे
स्यात्। दश दन्तोष्ठाः।

९२० । विभाषा समीपे । २ । ४ । १६ । अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे 'समाहार एव' इत्येवंरूपो नियमो वा स्यात् । उपदशं दन्तोष्ठम्—उपदशा दन्तोष्ठाः ।

९२१ । आनङ् ऋतो द्वन्द्वे । ६ । ३ । २५ । विद्यायोनिसंबन्धवाचिनामृदन्तानां द्वन्द्व आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । 'पुत्रेऽन्यतरस्याम्' (सू ९८०) इत्यतो मण्डूकप्लुत्या 'पुत्रे' इत्यनुवृत्तेः पितापुत्रौ ।

९२२ । देवताद्वन्द्वे च । ६ । ३ । २६ । इहोत्तरपदे पर आनङ् । मित्रावरुणौ । 'वायुशब्दप्रयोगे प्रतिषेधः' (वा ३९०७) । अग्निवायू—वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन 'ब्रह्मप्रजापती' इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतम्, नापि लोके प्रसिद्धं साहचर्यम् ।

९२३ । ईदग्नेः सोमवरुणयोः । ६ । ३ । २७ । देवताद्वन्द्वे इत्येव ।

९२४ । अग्नेः स्तुत्स्तोमसोमाः । ८ । ३ । ८२ । अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ।

९२५ । इद्वृद्धौ । ६ । ३ । २८ । वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्नीवरुणौ देवते अस्य आग्निवारुणम् । 'देवताद्वन्द्वे च' (सू १२३९) इत्युभयपदवृद्धिः । अलौकिकवाक्य आनङमीत्त्वं च बाधित्वा इत् । 'वृद्धौ' किम् । आग्नेन्द्रः । 'नेन्द्रस्य परस्य' (सू १२४०) इत्युत्तरपदवृद्धिप्रतिषेधः । 'विष्णौ न' (वा ३९०९) । आग्नावैष्णवम् ।

९२६ । दिवो द्यावा । ६ । ३ । २९ । देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षमे ।

९२७ । दिवसश्च पृथिव्याम् । ६ । ३ । ३० । 'दिवः' इत्येव । चाद्द्यावा । आदेशेऽकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ—द्यावापृथिव्यौ । 'छन्दसि दृष्टानुविधिः' । 'द्यावा चिदस्मै पृथिवी' 'दिवस्पृथिव्योररतिः' इत्यत्र पदकारा विसर्गं पठन्ति ।

९२८ । उषासोषसः । ६ । ३ । ३१ । 'उषस्'शब्दस्योषासादेशो देवताद्वन्द्वे । उषासासूर्यम् ।

९२९ । मातरपितरावुदीचाम् । ६ । ३ । ३२ । मातरपितरौ । 'उदीचाम्' किम् । मातापितरौ ।

९३० । द्वन्द्वाच्चुदषहान्तात्समाहारे । ५ । ४ । १०६ । चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच्स्यात्समाहारे । वाक्च त्वक्च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । 'समाहारे' किम् । प्रावृट्शरदौ ।

इति द्वन्द्वसमासप्रकरणम् ।

अथैकशेषप्रकरणम् ।

'सरूपाणाम्–' (सू १८८) । रामौ । रामाः । 'विरूपाणामपि समानार्थानाम्' (वा ७४७) । वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ—कुटिलदण्डौ ।

९३१ । वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । १ । २ । ६५ । यूना सहोक्तौ गोत्रं

शिष्यते गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । 'यूना' किम् । गार्ग्यगर्गौ । 'तल्लक्षणः' किम् । भागवित्ति-'वृद्धः' किम् । गर्गगार्ग्यायणौ । 'यूना' किम् । गार्ग्यगर्गौ । 'तल्लक्षणः' किम् । भागवित्ति-भागवित्तिकौ । 'कृत्स्नम्' किम् । गार्ग्यवात्स्यायनौ ।

९३२ । स्त्री पुंवच्च । १ । २ । ६६ । यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गाः । 'अस्त्रियाम्' इत्यनुवर्तमाने 'यञञोश्च' (सू ११०८) इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ।

९३३ । पुमान्स्त्रिया । १ । २ । ६७ । स्त्रिया सहोक्तौ पुमाञ्छिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ।

९३४ । भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । १ । २ । ६८ । भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ।

९३५ । नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । १ । २ । ६९ । अक्लीबेन सहोक्तौ क्लीबं शिष्यते, तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ।

९३६ । पिता मात्रा । १ । २ । ७० । मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ—मातापितरौ वा ।

९३७ । श्वशुरः श्वश्र्वा । १ । २ । ७१ । श्वश्र्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वशुरश्च श्वश्रूश्वशुरौ ।

९३८ । त्यदादीनि सर्वैर्नित्यम् । १ । २ । ७२ । सर्वैः सहोक्तौ त्यदादीनि, नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । 'त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' (वा ८०१) । स च यश्च यौ । 'पूर्वशेषोऽपि दृश्यते' इति भाष्यम् । स च यश्च तौ । 'त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि' (वा ७९९) । सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते । 'अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्' (वा ८००) । कुक्कुटमयूर्याविमे । मयुरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ।

९३९ । ग्राम्यपशुसंघेष्वतरुणेषु स्त्री । १ । २ । ७३ । एषु सहविवक्षायां स्त्री शिष्यते । 'पुमान्स्त्रिया' (सू ९३३) इत्यस्यापवादः । गाव इमाः । 'ग्राम्य—' इति किम् । रुरव इमे । 'पशु'ग्रहणं किम् । ब्राह्मणा इमे । 'संघेषु' किम् । एतौ गावौ । 'अतरुणेषु' किम् । वत्सा इमे । 'अनेकशफेष्विति वाच्यम्' (वा ८०५) । अश्वा इमे । इह सर्वत्रैकशेषे कृते सुबन्ताभावाद्द्वन्द्वो न । तेन 'शिरसी' 'शिरांसि' इत्यादौ समासस्येत्यन्तोदात्तः प्राप्नोति । एकवद्भावश्च न । 'पन्थानौ' 'पन्थानः' इत्यादौ समासान्तो न ।

इत्येकशेषप्रकरणम् ।

अथ सर्वसमासशेषप्रकरणम् ।

कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । 'परार्थाभिधानं वृत्तिः' । वृत्त्यर्थावबोधकं वाक्यं विग्रहः' । स द्विधा । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुर्लौकिकः ।

प्रयोगानर्होऽसाधुरलौकिकः। यथा राज्ञः पुरुषः। राजन् अस् पुरुष सु इत्यविग्रहो नित्यसमासः। अस्वपदविग्रहो वा। समासश्चतुर्विध इति प्रायो वादः। अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानामपि 'सह सुपा' (सू ६४९) इति विधानात्। पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्राचां प्रवादः प्रायोऽभिप्रायः। 'सूपप्रति' 'उन्मत्तगङ्गम्' इत्याद्यव्ययीभावे 'अतिमालादौ' तत्पुरुषे, 'द्वित्राः' इत्यादिबहुव्रीहौ, 'दन्तोष्ठम्' इत्यादि द्वन्द्वे चाभावात्। तत्पुरुषविशेषः कर्मधारयः। तद्विशेषो द्विगुः। अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव। तत्पुरुषस्य क्वचिदेवेत्युक्तम्। किं च।

सुपां सुपा तिङा नाम्ना धातुनाथ तिङां तिङा।
सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः॥

सुपां सुपा। राजपुरुषः। तिङा। पर्यभूषयत्। नाम्ना। कुम्भकारः। धातुना। कटप्रूः अजस्रम्। तिङां तिङा। पिबतखादता। खादतमोदता। तिङां सुपा। कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा। 'एहीडादयोऽन्यपदार्थे च' इति मयूरव्यंसकादौ पाठात्समासः।

इति सर्वसमासशेषप्रकरणम्।

अथ सर्वसमासान्तप्रकरणम्।

९४० । ऋक्पूरब्धूःपथामानक्षे । ५ । ४ । ७४ । अ अनक्ष इति छेदः। ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात्, अक्षे या धूस्तदन्तस्य तु न। अर्धर्चः। अनृच बह्वृचावध्येतर्येव। नेह। अनृक्साम। बह्वृक्सूक्तम्। विष्णोः पूर्विष्णुपुरम्। क्लीबत्वं लोकात्। विमलापं सरः।

९४१ । द्व्यन्तरुपसर्गेभ्योऽप ईत् । ६ । ३ । ९७ । अप इति कृतसमासान्तस्यानुकरणम्। षष्ठ्यर्थे प्रथमा। एभ्योऽपस्य ईत्स्यात्। द्विर्गता आपो यस्मिन्निति द्वीपम्। अन्तरीपम्। प्रतीपम्। समीपम्। समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम्। कृतसमासान्तग्रहणान्नेह। स्वप्। स्वपी। 'अवर्णान्ताद्वा' (वा ५०४५)। प्रेपम्। परेपम्। प्रापम्। परापम्[1]।

९४२ । ऊदनोर्देशे । ६ । ३ । ९८ । अनोः परस्यापस्य ऊत्स्याद्देशे। अनूपो देशः। राजधुरा। अक्षे तु अक्षधूः। दृढधूरक्षः। सखिपथो रम्यपथो देशः।

९४३ । अच्प्रत्यन्ववपूर्वात्सामलोम्नः । ५ । ४ । ७५ । एतत्पूर्वात्सामलोमान्तात्समासादच्स्यात्। प्रतिसामम्। अनुसामम्। अवसामम्। प्रतिलोमम्। अनुलोमम्। 'कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते'[2] (वा ५०४६)। कृष्णभूमः। उदग्भूमः। पाण्डुभूमः।

---

१ इदं च प्रकृतसूत्रे 'प्रापं परापम्' इति 'गतिश्च' इति सूत्रे 'प्रेपं परेपम्' इति भाष्योदाहरणलब्धमपि प्रपराविषयकमेवेति भाति। २ इदं 'अच्' इति योगविभागलब्धम्—इति काशिका।

द्विभूमः प्रासादः। 'संख्याया नदीगोदावरीभ्यां च' (वा ५०४७)। पञ्चनदम्। सप्तगोदावरम्। 'अच्' इति योगविभागादन्यत्रापि। पद्मनाभः।

९४४। अक्ष्णोऽदर्शनात्। ५।४। ७६। अचक्षुःपर्यायादक्ष्णोऽच्स्यात्समासान्तः। गवामक्षीव गवाक्षः।

९४५। अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः। ५।४। ७७। एते पञ्चविंशतिरजन्ता निपात्यन्ते। आद्यास्त्रयो बहुव्रीहयः। अविद्यमानानि चत्वार्यस्य। अचतुरः। विचतुरः। सुचतुरः। 'त्र्युपाभ्यां चतुरोऽजिष्यते' (वा ३३९१)। त्रिचतुरः। चतुर्णां समीपे उपचतुराः। तत एकादश द्वन्द्वाः। स्त्रीपुंसौ। धेन्वनडुहौ। ऋक्सामे। वाङ्मनसे। अक्षिणी च भ्रुवौ चाक्षिभ्रुवम्। दाराश्च गावश्च दारगवम्। ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्। निपातनाट्टिलोपः। पदष्ठीवम्। निपातनात्पादशब्दस्य पद्भावः। नक्तं च दिवा च नक्तंदिवम्। रात्रौ च दिवा च रात्रिंदिवम्। रात्रेर्मान्तत्वं निपात्यते। अहनि च दिवा चाहर्दिवम्। वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनीत्यर्थः। सरजसमिति साकल्येऽव्ययीभावः। बहुव्रीहौ तु सरजः पङ्कजम्। निश्चितं श्रेयो निःश्रेयसम्। तत्पुरुष एव। नेह। निःश्रेयान्पुरुषः। पुरुषस्यायुः पुरुषायुषम्। ततो द्विगुः। द्व्यायुषम्। त्र्यायुषम्। ततो द्वन्द्वः। ऋग्यजुषम्। ततस्त्रयः कर्मधारयाः। जातोक्षः। महोक्षः। वृद्धोक्षः। शुनः समीपमुपशुनम्। टिलोपाभावः संप्रसारणं च निपात्यते। गोष्ठे श्वा गोष्ठश्वः।

९४६। ब्रह्महस्तिभ्यां वर्चसः। ५। ४। ७८। अच्स्यात्। ब्रह्मवर्चसम्। हस्तिवर्चसम्। 'पल्यराजभ्यां चेति वक्तव्यम्' (वा ३३९२)। पल्यवर्चसम्। राजवर्चसम्।

९४७। अवसमन्धेभ्यस्तमसः। ५। ४। ७९। अवतमसम्। संतमसम्। अन्धयतीत्यन्धम्। पचाद्यच्। अन्धं तमोऽन्धतमसम्।

९४८। श्वसो वसीयःश्रेयसः। ५। ४। ८०। वसुशब्दः प्रशस्तवाची। तत ईयसुनि वसीयः। श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह। मयूरव्यंसकादित्वात्समासः। श्वोवसीयसम्। श्वःश्रेयसं ते भूयात्।

९४९। अन्ववतप्ताद्रहसः। ५। ४। ८१। अनुरहसम्। अवरहसम्। तप्तरहसम्।

९५०। प्रतेरुरसः सप्तमीस्थात्। ५। ४। ८२। उरसि प्रति प्रत्युरसम्। विभक्त्यर्थेऽव्ययीभावः।

९५१। अनुगवमायामे। ५। ४। ८३। एतन्निपात्यते दीर्घत्वे। अनुगवं यानम्। 'यस्य चायामः' (सू ६७०) इति समासः।

९५२। द्विस्तावा त्रिस्तावा वेदिः। ५। ४। ८४। अच्प्रत्ययाट्टिलोपः समासश्च निपात्यते। यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाश्वमेधादौ तत्रेदं निपातनम्। 'वेदिः' इति किम्। द्विस्तावती त्रिस्तावती रज्जुः।

---

१ इदं 'अच्' इति योगविभागलब्धम् इति—काशिका।

९५३। उपसर्गादध्वनः। ५। ४। ८५। प्रगतोऽध्वानं प्राध्वो रथः।

९५४। न पूजनात्। ५। ४। ६९। पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा। अतिराजा। 'स्वतिभ्यामेव' (वा ३३४६)। नेह। परमराजः। 'पूजनात' किम्। गामतिक्रान्तोऽतिगवः। 'बहुव्रीहौ सक्थ्यक्ष्णोः–' (सू ८५२) इत्यतः प्रागेवायं निषेधः। नेह। सुसक्थः। स्वक्षः।

९५५। किमः क्षेपे। ५। ४। ७०। क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः। कुत्सितो राजा किंराजा। किंसखा। किंगौः। 'क्षेपे' किम्। किंराजः। किंसखः। किंगवः।

९५६। नञस्तत्पुरुषात्। ५। ४। ७१। समासान्तो न। अराजा। असखा। 'तत्पुरुषात्' किम्। अधुरं शकटम्।

९५७। पथो विभाषा। ५। ४। ७२। नञ्पूर्वात्पथो वा समासान्तः। अपथम्–अपन्थाः। 'तत्पुरुषात्' इत्येव। अपथो देशः। अपथं वर्तते।

इति सर्वसमासान्तप्रकरणम्।

अथालुक्समासप्रकरणम्।

९५८। अलुगुत्तरपदे। ६। ३। १। अलुगधिकारः प्रागानङः, उत्तरपदाधिकारस्त्वापादसमाप्तेः।

९५९। पञ्चम्याः स्तोकादिभ्यः। ६। ३। २। एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे। स्तोकान्मुक्तः। एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः। 'उत्तरपदे' किम्। निष्क्रान्तः स्तोकान्निस्तोकः। 'ब्राह्मणाच्छंसिन उपसंख्यानम्' (वा ३८७८)। ब्राह्मणे विहितानि शस्त्राण्युपचाराद्ब्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः। द्वितीयार्थे पञ्चम्युपसंख्यानादेव।

९६०। ओजःसहोऽम्भस्तमसस्तृतीयायाः। ६। ३। ३। ओजसाकृतमित्यादि 'अञ्जस उपसंख्यानम्' (वा ३८८०)। अञ्जसाकृतम्। आर्जवेन कृतमित्यर्थः। 'पुंसानुजो जनुषान्ध इति च' (वा ३८८१)। यस्याग्रजः पुमान्स पुंसानुजः। जनुषान्धो जात्यन्धः।

९६१। मनसः संज्ञायाम्। ६। ३। ४। मनसागुप्ता।

९६२। आज्ञायिनि च। ६। ३। ५। 'मनसः' इत्येव। मनसा ज्ञातुं शीलमस्य मनसाज्ञायी।

९६३। आत्मनश्च। ६। ३। ६। आत्मनस्तृतीयाया अलुक्स्यात्। 'पूरण इति वक्तव्यम्' (वा ३८८२)। पूरणप्रत्ययान्त उत्तरपद इत्यर्थः। आत्मनापञ्चमः। 'जनार्दनस्त्वात्मचतुर्थ एव' इति बहुव्रीहिर्बोध्यः। 'पूरणे' किम्। आत्मकृतम्।

---

१ दीक्षितेन 'आत्मनश्च पूरणे' (वा ३८८२) इति वार्तिकतः 'आत्मनश्च' इत्यंशं पृथक्कृत्य 'वैयाकरणाख्यायाम्–' इति सूत्रेऽनुवृत्त्यर्थं सूत्रत्वमङ्गीकृतम्। परं तु 'काम्ये रोरेव' इति वार्तिकस्य 'सोऽपदादौ' इति सूत्रस्थस्यैव 'इणः षः' इति सूत्रेऽप्यनुवृत्तिवदत्राप्यनुवृत्तौ दोषाभावेन वार्तिकत्वत्यागे सूत्रत्वाङ्गीकारे बीजाभावः।

९६४। वैयाकरणाख्यायां चतुर्थ्याः। ६। ३। ७। 'आत्मनः' इत्येव। आत्मनेपदम्। आत्मनेभाषा। तादर्थ्ये चतुर्थी। 'चतुर्थी' इति योगविभागात्समासः।

९६५। परस्य च। ६। ३। ८। परस्मैपदम्। परस्मैभाषा।

९६६। हलदन्तात्सप्तम्याः संज्ञायाम्। ६। ३। ९। हलन्तादन्ताच्च सप्तम्या अलुक्स्संज्ञायाम्। त्वचिसारः।

९६७। गवियुधिभ्यां स्थिरः। ८। ३। ९५। आभ्यां स्थिरस्य सस्य षः स्यात्। गविष्ठिरः। अत्र गवीति वचनादेवालुक्। युधिष्ठिरः। अरण्येतिलकः। अत्र 'संज्ञायाम्' (सू ७२१) इति सप्तमीसमासः। 'हृद्द्युभ्यां च' (वा ३८८५)। हृदिस्पृक्। दिविस्पृक्।

९६८। कारनाम्नि च प्राचां हलादौ। ६। ३। १०। प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक्। मुकुटेकार्षापणम्। दृषदिमाषकः। पूर्वेण सिद्धे नियमार्थम्। कारनाम्न्येव प्राचामेव हलादावेवेति। 'कारनाम्नि' किम्। अभ्याहितपशुः। कारादन्यस्यैतद्देयस्य नाम। 'प्राचाम्' किम्। यूथपशुः। 'हलादौ' किम्। अविकटोरणः। 'हलदन्तात्' किम्। नद्यां दोहो नदीदोहः।

९६९। मध्याद्गुरौ। ६। ३। ११। मध्येगुरुः। 'अन्ताच्च' (वा ३८९४)। अन्तेगुरुः।

९७०। अमूर्धमस्तकात्स्वाङ्गादकामे। ६। ३। १२। कण्ठेकालः। उरसिलोमा। 'अमूर्धमस्तकात्' किम्। मूर्धशिखः। मस्तकशिखः। 'अकामे' किम्। मुखे कामोऽस्य मुखकामः।

९७१। बन्धे च विभाषा। ६। ३। १३। हलदन्तात्सप्तम्या अलुक्। हस्तेबन्धः। हस्तबन्धः। 'हलदन्त–' इति किम्। गुप्तिबन्धः।

९७२। तत्पुरुषे कृति बहुलम्। ६। ३। १४। स्तम्बेरमः–स्तम्बरमः। कर्णेजपः–कर्णजपः। 'क्वचिन्न'। कुरुचरः।

९७३। प्रावृट्शरत्कालदिवां जे। ६। ३। १५। प्रावृषिजः। शरदिजः। कालेजः। दिविजः। पूर्वस्यायं प्रपञ्चः।

९७४। विभाषा वर्षक्षरशरवरात्। ६। ३। १६। एभ्यः सप्तम्या अलुग्जे। वर्षेजः–वर्षजः। क्षरेजः–क्षरजः। शरेजः–शरजः। वरेजः–वरजः।

९७५। घकालतनेषु कालनाम्नः। ६। ३। १७। सप्तम्या विभाषया लुक्स्यात्। पूर्वाह्णेतरे–पूर्वाह्णतरे। पूर्वाह्णेतमे–पूर्वाह्णतमे। काल। पूर्वाह्णेकाले–पूर्वाह्णकाले। तन। पूर्वाह्णेतने–पूर्वाह्णतने।

९७६। शयवासवासिष्वकालात्। ६। ३। १८। खेशयः–खशयः। ग्रामेवासः–ग्रामवासः। ग्रामेवासी–ग्रामवासी। 'हलदन्तात्' इत्येव। भूमिशयः। 'अपो योनियन्मतुषु'[1] (वा ३८७६)। अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः। अप्सु भवोऽप्सव्यः। अप्सुमन्तावाज्यभागौ।

---

१ अयं पाठो हरदत्तानुसारेण। 'मतिषु' इति युक्तः पाठः। 'एकवच्च' इत्यस्यातिप्रसङ्गभञ्जनेनाप्सुजाप्सुचरादिवदस्य (अप्सुमतिः) भाष्ये उपन्यासात्। नहि 'अप्सुमन्तौ' इत्यत्र तत्प्रसङ्गोऽस्ति। शब्दपरतया तस्यैकत्वमात्रार्थत्वात्। किं च 'मतुषु' इति पाठे फलं चिन्त्यम्। 'अस्यवामीयम्' इत्यादाविव लुकोऽप्राप्तेः। इति–शेखरः।

९७७। नेन्सिद्धबध्नातिषु च। ६। ३। १९। इन्नन्तादिषु सप्तम्या अलुन्न। स्थण्डिलशायी। सांकाश्यसिद्धः। चक्रबन्धः।

९७८। स्थे च भाषायाम्। ६। ३। २०। सप्तम्या अलुन्न। समस्थः। 'भाषायाम्' किम्। कृष्णोऽस्याखरेष्ठः।

९७९। षष्ठ्या आक्रोशे। ६। ३। २१। चौरस्यकुलम्। 'आक्रोशे' किम्। ब्राह्मणकुलम्। 'वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु' (वा ३८९७)। वाचोयुक्तिः। दिशोदण्डः। पश्यतोहरः। 'आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च' (वा ३८९८-३८९९)। अमुष्यापत्यमामुष्यायणः। नडादित्वात्फक्। अमुष्य पुत्रस्य भाव आमुष्यपुत्रिका। मनोज्ञादित्वाद्वुञ्। एवमामुष्यकुलिका। 'देवानांप्रिय इति च मूर्खे' (वा ३९००)। अन्यत्र देवप्रियः। 'शेपपुच्छलाङ्गूलेषु शुनः' (वा ३९०१)। शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः। 'दिवश्च दासे' (वा ३९०२)। दिवोदासः।

९८०। पुत्रेऽन्यतरस्याम्। ६। ३। २२। षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम्। दास्याः पुत्रः-दासीपुत्रः। 'निन्दायाम्' किम्। ब्राह्मणीपुत्रः।

९८१। ऋतो विद्यायोनिसंबन्धेभ्यः। ६। ३। २३। विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तात्षष्ठ्या अलुक्। होतुरन्तेवासी। होतुःपुत्रः। पितुरन्तेवासी। पितुःपुत्रः। 'विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्' (वा ३९०३)। नेह। होतृधनम्।

९८२। विभाषा स्वसृपत्योः। ६। ३। २४। ऋदन्तात्षष्ठ्या अलुग्वा स्वसृपत्योः परयोः।

९८३। मातुःपितुर्भ्यामन्यतरस्याम्। ८। ३। ८५। आभ्यां स्वसुः सस्य षो वा स्यात्समासे। मातुःष्वसा-मातुःस्वसा। पितुःष्वसा-पितुःस्वसा। लुक्पक्षे तु।

९८४। मातृपितृभ्यां स्वसा। ८। ३। ८४। आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे। मातृष्वसा। पितृष्वसा। असमासे तु। मातुः स्वसा। पितुः स्वसा।

इत्यलुक्समासप्रकरणम्।

अथ समासाश्रयविधिप्रकरणम्।

९८५। घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः। ६। ३। ४३। भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्याद्घरूपकल्पप्प्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु। ब्राह्मणितरा। ब्राह्मणितमा। ब्राह्मणिरूपा। ब्राह्मणिकल्पा। ब्राह्मणिचेली। ब्राह्मणिब्रुवा। ब्राह्मणिगोत्रेत्यादि। ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावोऽपि निपात्यते। चेलडादीनि वृत्तिविषये कुत्सनवाचीनि। तैः 'कुत्सितानि कुत्सनैः' (सू ७३२) इति समासः। 'ङ्यः' किम्। दत्तातरा। 'भाषितपुंस्कात्' किम्। आमलकीतरा। कुवलीतरा।

९८६। नद्याः शेषस्यान्यतरस्याम्। ६। ३। ४४। अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात्। ब्रह्मबन्धुतरा-ब्रह्मबन्धूतरा। स्त्रितरा-स्त्रीतरा। 'कृन्नद्या न' (वा ३९२८)। लक्ष्मीतरा।

९८७। उगितश्च। ६। ३। ४५। उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा

स्यात्। विदुषितरा। ह्रस्वाभावपक्षे तु 'तसिलादिषु–' (सू ८३६) इति पुंवत्। विद्वत्त... वृत्त्यादिषु 'विदुषीतरा' इत्यप्युदाहृतं तन्निर्मूलम्।

९८८। हृदयस्य हृल्लेखयदण्लासेषु। ६। ३। ५०। हृदयं लिखतीति हृल्लेखः। ... यस्य प्रियं हृद्यम्। हृदयस्येदं हार्दम्। हृल्लासः। 'लेख–' इत्यण्णन्तस्य ग्रहणम्। घञि ... हृदयलेखः। लेखग्रहणं ज्ञापकम् 'उत्तरपदाधिकारे तदन्तविधिर्नास्ति' (प २६) इति।

९८९। वा शोकष्यञ्रोगेषु। ६। ३। ५१। हृच्छोकः–हृदयशोकः। सौहार्द्यम्–सौ... द्यम्। हृद्रोगः–हृदयरोगः। हृदयशब्दपर्यायो हृच्छब्दोऽप्यस्ति। तेन सिद्धे प्रपञ्चार्थमिदम्।

९९०। पादस्य पदाज्यातिगोपहतेषु। ६। ३। ५२। एषूत्तरपदेषु पादस्य 'पद' इत्यदन्त आदेशः स्यात्। पादाभ्यामजतीति पदाजिः। पदातिः। 'अज्यतिभ्यां पादे च' (उ ५७०–५७१) इतीण्प्रत्ययः। अजेर्व्यभावो निपातनात्। पदगः। पदोपहतः।

९९१। पद्यत्यतदर्थे। ६। ३। ५३। पादस्य पत्स्यादतदर्थे यति परे। पादौ विध्यन्ति पद्याः शर्कराः। 'अतदर्थे' किम्। पादार्थमुदकं पाद्यम्। 'पादार्घाभ्यां च' (सू २०९३) इति यत्। 'इके चरतावुपसंख्यानम्' (वा ३९५८)। पादाभ्यां चरति पदिकः। पर्पादित्वात्ष्ठन्।

९९२। हिमकाषिहतिषु च। ६। ३। ५४। पद्धिमम्। पत्काषी। पद्धतिः।

९९३। ऋचः शे। ६। ३। ५५। ऋचः पादस्य पत्स्याच्छे परे। गायत्रीं पच्छः शंसति। पादंपादमित्यर्थः। 'ऋचः' किम्। पादशः कार्षापणं ददाति।

९९४। वा घोषमिश्रशब्देषु। ६। ३। ५६। पादस्य पत्। पद्घोषः–पादघोषः। पन्मिश्रः–पादमिश्रः। पच्छब्दः–पादशब्दः। 'निष्के चेति वाच्यम्' (वा ३९५९)। पन्निष्कः–पादनिष्कः।

९९५। उदकस्योदः संज्ञायाम्। ६। ३। ५७। उदमेघः। 'उत्तरपदस्य चेति वक्तव्यम्' (वा ३९६१)। क्षीरोदः।

९९६। पेषंवासवाहनधिषु च। ६। ३। ५८। उदपेषं पिनष्टि। उदवासः। उदवाहनः। उदधिर्घटः। समुद्रे तु पूर्वेण सिद्धम्।

९९७। एकहलादौ पूरयितव्येऽन्यतरस्याम्। ६। ३। ५९। उदकुम्भः–उदककुम्भः। 'एक–' इति किम्। उदकस्थाली। 'पूरयितव्ये' इति किम्। उदकपर्वतः।

९९८। मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च। ६। ३। ६०। उदमन्थः–उदकमन्थः। उदौदनः–उदकौदनः।

९९९। इको ह्रस्वोऽङ्यो गालवस्य। ६। ३। ६१। इगन्तस्याङ्यन्तस्य ह्रस्वो वा स्यादुत्तरपदे। ग्रामणिपुत्रः–ग्रामणीपुत्रः। 'इकः' किम्। रमापतिः। 'अङ्यः' इति किम्। गौरीपतिः। 'गालव'ग्रहणं पूजार्थम्। 'अन्यतरस्याम्' इत्यनुवृत्तेः। 'इयङुवङ्भाविनामव्ययानां च नेति वाच्यम्' (वा ३९६३)। श्रीमदः। भ्रूभङ्गः। शुक्लीभावः। 'अभ्रूकुंसादीनामिति वक्तव्यम्' (वा ३९६४)। भ्रुकुंसः–भ्रूकुंसः। भ्रुकुटिः–भ्रूकुटिः। अकारोऽनेन वि... यत इति व्याख्यान्तरम्। भ्रकुंसः। भ्रकुटिः। भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः। भ्रुवः कुटिः कौटिल्यम्।

१००० । एक तद्धिते च । ६ । ३ । ६२ । एकशब्दस्य ह्रस्वः स्यात्तद्धित उत्तरपदे । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ।

१००१ । ङ्यापोः संज्ञाछन्दसोर्बहुलम् । ६ । ३ । ६३ । रेवतिपुत्रः । अजक्षीरम् ।

१००२ । त्वे च । ६ । ३ । ६४ । त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम्–अजात्वम् । रोहिणित्वम्–रोहिणीत्वम् ।

१००३ । ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे । ६ । १ । १३ । ष्यङन्तस्य पूर्वपदस्य संप्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ।

१००४ । संप्रसारणस्य । ६ । ३ । १३९ । संप्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । 'स्त्रीप्रत्यये चानुपसर्जने न' (प २७) इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारीषगन्ध्यापुत्रः ।

१००५ । बन्धुनि बहुव्रीहौ । ६ । १ । १४ । बन्धुशब्द उत्तरपदे ष्यङः संप्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । 'बहुव्रीहौ' इति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः । क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया । 'मातज्मातृकमातृषु वा' (वा ३४४९) । कारीषगन्धीमातः–कारीषगन्ध्यामातः । कारीषगन्धीमातृकः–कारीषगन्ध्यामातृकः । कारीषगन्धीमाता–कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः । 'नद्यृतश्च' (सू ८३३) इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह । कारीषगन्ध्याया माता कारीषगन्ध्यामाता । त्रित्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ।

१००६ । इष्टकेषीकामालानां चिततूलभारिषु । ६ । ३ । ६५ । इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम् , इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारी । उत्पलमालभारी ।

१००७ । कारे सत्यागदस्य । ६ । ३ । ७० । मुम्स्यात् । सत्यंकारः । अगदंकारः । 'अस्तोश्चेति वक्तव्यम्' (वा ३९७३) । अस्तुंकारः । 'धेनोर्भव्यायाम्' (वा ३९७५) । धेनुंभव्या । 'लोकस्य पृणे' (वा ३९७६) । लोकंपृणः । 'पृणः' इति मूलविभुजादित्वात्कः । 'इत्येऽनभ्याशस्य' (वा ३९७७) । अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः । 'भ्राष्ट्राग्न्योरिन्धे' (वा ३९७८) । भ्राष्ट्रमिन्धः । अग्निमिन्धः । 'गिलेऽगिलस्य' (वा ३९७९) । तिमिंगिलः । 'अगिलस्य' किम् । गिलगिलः । 'गिलगिले च' (वा ३९८०) । तिमिंगिलगिलः । 'उष्णभद्रयोः करणे' (वा ३९८१) । उष्णंकरणम् । भद्रंकरणम् ।

१००८ । रात्रेः कृति विभाषा । ६ । ३ । ७२ । रात्रिंचरः–रात्रिचरः । रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु 'अरुर्द्विषत्–' (सू २९४२) इति नित्यमेव वक्ष्यते । रात्रिंमन्यः ।

१००९ । सहस्य सः संज्ञायाम् ६ । ३ । ७८ । उत्तरपदे । सपलाशम् । 'संज्ञायाम्' किम् । सहयुध्वा ।

१०१० । ग्रन्थान्ताधिके च । ६ । ३ । ७९ । अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ।

१०११ । द्वितीये चानुपाख्ये । ६ । ३ । ८० । अनुमेये द्वितीये सहस्य सः स्या
सराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयानुमीयते ।

१०१२ । समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु । ६ । ३ । ८४ । समानस्य सः स्या
त्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । यो नः सनु
'तत्र भवः' इत्यर्थे 'सगर्भसयूथसनुताद्यत्' (सू ३४६०) । 'अमूर्धादिषु' किम् । समानमू
समानप्रभृतयः । समानोदर्काः । 'समानस्य' इति योगो विभज्यते । तेन सपक्षः सा
सजातीयमित्यादि सिद्धमिति काशिका । अथ वा सहशब्दः सदृशवचनोऽस्ति । स
सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ।

१०१३ । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ।
३ । ८५ । एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि ।

१०१४ । चरणे ब्रह्मचारिणि । ६ । ३ । ८६ । ब्रह्मचारिण्युत्तरपदे समानस्य सः
चरणे समानत्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः । तदध्ययनार्थं व्रतमपि ब्रह्म त
तीति ब्रह्मचारी । समानः सः सब्रह्मचारी ।

१०१५ । तीर्थे ये । ६ । ३ । ८७ । तीर्थ उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य
स्यात् । सतीर्थ्यः । एकगुरुकः । 'समानतीर्थे वासी' (सू १६९८) इति यत्प्रत्ययः ।

१०१६ । विभाषोदरे । ६ । ३ । ८८ । यादौ प्रत्यये विवक्षित इत्येव । सोदर्यः—समानो

१०१७ । दृग्दृशवतुषु । ६ । ३ । ८९ । सदृक्—सदृशः । 'दृक्षे चेति वक्तव्यम्' (वा ३९
सदृक्षः । वतुरुत्तरार्थः ।

१०१८ । इदंकिमोरीश्की । ६ । ३ । ९० । दृग्दृशवतुषु इदम ईश् किमः की स्या
ईदृक्—ईदृशः । कीदृक्—कीदृशः । वतूदाहरणं वक्ष्यते । 'दृक्षे चेति वक्तव्यम्' (वा ३९
ईदृक्षः । कीदृक्षः । 'आ सर्वनाम्नः' (सू ४३०) । 'दृक्षे च' (वा ३९९२) । तादृक्—ता
तावान्—तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृशः—अमूदृक्—अमूदृक्षः ।

१०१९ । समासेऽङ्गुलेः सङ्गः । ८ । ३ । ८० । अङ्गुलिशब्दात्सङ्गस्य सस्य मू
स्यात्समासे । अङ्गुलिषङ्गः । 'समासे' किम् । अङ्गुलेः सङ्गः ।

१०२० । भीरोः स्थानम् । ८ । ३ । ८१ । भीरुशब्दात्स्थानस्य सस्य मूर्धन्यः स
मासे । भीरुष्ठानम् । असमासे तु भीरोः स्थानम् ।

१०२१ । ज्योतिरायुषः स्तोमः । ८ । ३ । ८३ । आभ्यां स्तोमस्य सस्य मू
समासे ज्योतिष्टोमः । आयुष्टोमः । 'समासे' किम् । ज्योतिषः स्तोमः ।

१०२२ । सुषामादिषु च । ८ । ३ । ९८ । सस्य मूर्धन्यः । शोभनं साम यस्य सु
सुषन्धिः ।

१०२३ । एति[1] संज्ञायामगात् । ८ । ३ । ९९ । (ग १८२) । सस्य मूर्धन्यः । हरि
'एति' किम् । हरिसक्थम् । 'संज्ञायाम्' किम् । पृथुसेनः । 'अगकारात्' किम् । विष्व
'इण्कोः' इत्येव । सर्वसेनः ।

१०२४ । नक्षत्राद्वा[2] । ८ । ३ । १०० । (ग १८३) । एति सस्य संज्ञायामगका

१-२ सुषामाद्यन्तर्गणसूत्रे एते-इति तत्त्वबोधिनी ।

धन्यो वा । रोहिणीषेणः—रोहिणीसेनः । 'अगकारात्' किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ।

१०२५ । अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु । ६ । ३ । ९९ । अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । 'अषष्ठी--' इत्यादि किम् । अन्यस्यान्येन वाशीरन्याशीः । 'कारके छे च नायं निषेधः'[1] (वा ५०४८) । अन्यस्य कारकोऽन्यत्कारकः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः ।

१०२६ । अर्थे विभाषा । ६ । ३ । १०० । अन्यदर्थः । अन्यार्थः ।

१०२७ । कोः कत्तत्पुरुषेऽचि । ६ । ३ । १०१ । अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । 'तत्पुरुषे' किम् । कूष्ट्रो राजा । 'त्रौ च' (वा ३९९८) । कुत्सितास्त्रयः कत्त्रयः ।

१०२८ । रथवदयोश्च । ६ । ३ । १०२ । कद्रथः । कद्वदः ।

१०२९ । तृणे च जातौ । ६ । ३ । १०३ । कत्तृणम् ।

१०३० । का पथ्यक्षयोः । ६ । ३ । १०४ । कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ।

१०३१ । ईषदर्थे । ६ । ३ । १०५ । ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ।

१०३२ । विभाषा पुरुषे । ६ । ३ । १०६ । कापुरुषः—कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ।

१०३३ । कवं चोष्णे । ६ । ३ । १०७ । उष्णशब्द उत्तरपदे कवं का च वा स्यात् । कवोष्णम्—कोष्णम्—कदुष्णम् ।

१०३४ । पृषोदरादीनि यथोपदिष्टम् । ६ । ३ । १०९ । पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्युः । पृषदुदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य वः । उत्तरपदादेश्च लत्वम् ।

भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ।
गूढोऽत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥

'दिक्छब्देभ्यस्तीरस्य तारभावो वा' (वा ३९९९) । दक्षिणतारम्—दक्षिणतीरम् । उत्तरतारम्—उत्तरतीरम् । 'दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च' (वा ४००१) । दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । 'आतश्च–' (सू २८९८) इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य 'बृ' आदेशः । सदेरधिकरणे डट् । आकृतिगणोऽयम् ।

---

१ अत्र च "अषष्ठ्यतृतीयास्थस्येत्युच्यते । तत्रेदं न सिध्यति—अन्यस्येदमन्यदीयम् । अन्यस्य कारकोऽन्यत्कारकः इति एवं तर्हि--अविशेषेण 'अन्यस्य दुक् छकारकयोः' ततो वक्ष्यामि 'अषष्ठ्यतृतीयास्थस्याशीराशास्थास्थितोत्सुकोऽतिरागेषु' इति" इति भाष्यमेव मानम् ।

१०३५ । संहितायाम् । ६ । ३ । ११४ । अधिकारोऽयम् ।

१०३६ । कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य । ६ । ३ । ११५ । कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । 'लक्षणस्य' किम् । शोभनकर्णः । 'अविष्टादीनाम्' किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ।

१०३७ । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । ६ । ३ । ११६ । क्विबन्तेषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । 'क्वौ' इति किम् । परीनहनम् । 'विभाषा पुरुषे' (सू १०३२) इत्यतो मण्डूकप्लु... 'विभाषा' अनुवर्तते । सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ।

१०३८ । वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् । ६ । ३ । ११७ । कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ।

१०३९ । वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः । ८ । ४ । ४ । वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । 'एभ्य एव' इति किम् । अ... पत्रवनम् । वनस्याग्रेऽग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिका... मात्रे प्रथमा । किंशुलुका गिरिः ।

१०४० । वले । ६ । ३ । ११८ । वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ।

१०४१ । मतौ बह्वचोऽनजिरादीनाम् । ६ । ३ । ११९ । अमरावती । 'अनजिरादीनाम्' किम् । अजिरवती । 'बह्वचः' किम् । व्रीहिमती । 'संज्ञायाम्' इत्येव । ने... वलयवती ।

१०४२ । शरादीनां च । ६ । ३ । १२० । शरावती ।

१०४३ । इको वहेऽपीलोः । ६ । ३ । १२१ । इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । कपीवहम् । 'इकः' किम् । पिण्डवहम् । 'अपीलोः' किम् । पीलुवहम् । 'अपील्वादीना... वाच्यम्' (वा ४००९) । दारुवहम् ।

१०४४ । उपसर्गस्य घञ्यमनुष्ये बहुलम् । ६ । ३ । १२२ । उपसर्गस्य बहुलं दी... स्याद्घञन्ते परे न तु मनुष्ये । परीपाकः–परिपाकः । 'अमनुष्ये' किम् । निषादः ।

१०४५ । इकः काशे । ६ । ३ । १२३ । इगन्तस्योपसर्गस्य दीर्घः स्यात्का... वीकाशः । नीकाशः । 'इकः' किम् । प्रकाशः ।

१०४६ । अष्टनः संज्ञायाम् । ६ । ३ । १२५ । उत्तरपदे दीर्घः । अष्टापदम् । 'सं... याम्' किम् । अष्टपुत्रः ।

१०४७ । चितेः कपि । ६ । ३ । १२७ । एकचितीकः ।

१०४८ । नरे संज्ञायाम् । ६ । ३ । १२९ । विश्वानरः ।

१०४९ । मित्रे चर्षौ । ६ । ३ । १३० । विश्वामित्रः । 'ऋषौ' किम् । विश्वमित्रो ...

वक्तः। 'शंनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः' (वा ५०४९)। श्वादन्त इत्यादि।

१०५० । प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि । ८ । ४ । ५ । एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ।

१०५१ । विभाषौषधिवनस्पतिभ्यः । ८ । ४ । ६ एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम्-दूर्वावनम् । शिरीषवणम्-शिरीषवनम् । 'द्व्यच्त्र्यज्भ्यामेव' (वा ४९८४) । नेह । देवदारुवनम् । 'इरिकादिभ्यः प्रतिषेधो वक्तव्यः' (वा ४९८५)। इरिकावनम् । मिरिकावनम् ।

१०५२ । वाहनमाहितात् । ८ । ४ । ८ । आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । 'आहितात्' किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ।

१०५३ । पानं देशे । ८ । ४ । ९ । पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयत इति पानम् । कर्मणि ल्युट् ।

१०५४ । वा भावकरणयोः । ८ । ४ । १० । 'पानस्य' इत्येव । क्षीरपानम्-क्षीरपाणम् 'गिरिनद्यादीनां वा' (वा ४९८९) । गिरिनदी-गिरिणदी । चक्रनितम्बा-चक्रणितम्बा ।

१०५५ । प्रातिपदिकान्तनुम्विभक्तिषु च । ८ । ४ । ११ । पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो[1] वा स्यात् । प्रातिपदिकान्ते । माषवापिणौ । नुमि । व्रीहिवापाणि । विभक्तौ । माषवापेण । पक्षे माषवापिनावित्यादि । 'उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम्' (वा ४९९०) । नेह । गर्गाणां भगिनी गर्गभगिनी । अत एव नुम्ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् । न तूत्तरपदस्य । किं च । 'प्रहिण्वन्' इत्यादा हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । 'प्रेन्वनम्' इत्यादौ तु क्षुभ्नादित्वान्न । युवादेर्न । (वा ४९९१) रम्ययूना । परिपक्वानि । 'एकाजुत्तरपदे णः' (सू ३०७) । 'नित्यम्' इत्युक्तम् । वृत्रहणौ । हरिं मानयतीति क्विपि हरिमाणी । नुमि । क्षीरपाणि । विभक्तौ क्षीरपेण । रम्यविणा ।

१०५६ । कुमति च । ८ । ४ । १३ । कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ।

१०५७ । पदव्यवायेऽपि । ८ । ४ । ३८ । पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन । 'अतद्धित इति वाच्यम्' (वा ५०१५) । आर्द्रगोमयेण । शुष्कगोमयेण ।

१०५८ । कुस्तुम्बुरूणि जातिः । ६ । १ । १४३ । अत्र सुण्निपात्यते । कुस्तुम्बुरु-धान्याकम् । क्लीबत्वमतन्त्रम् । 'जातिः' किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ।

१०५९ । अपरस्पराः क्रियासातत्ये । ६ । १ । १४४ । सुण्निपात्यते । अपरस्पराः सार्थाः गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । 'क्रिया-' इति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ।

१०६० । गोष्पदं सेवितासेवितप्रमाणेषु । ६ । १ । १४५ । सुट् सस्य षत्वं च

---

१ इदं च 'अन्येषामपि-' (६ । ३ । १३७) इति सूत्रप्रपञ्चभूतम् ।

निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते । अगोष्पदार-ण्यानि । प्रमाणे । गोष्पदमात्रं क्षेत्रम् । 'सेवित–' इत्यादि किम् । गोः पदं गोपदम् ।

१०६१ । आस्पदं प्रतिष्ठायाम् । ६ । १ । १४६ । आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । 'प्र–' इति किम् । आपदापदम् ।

१०६२ । आश्चर्यमनित्ये । ६ । १ । १४७ । अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । 'अनित्ये' किम् । आचर्यं कर्म शोभनम् ।

१०६३ । वर्चस्केऽवस्करः । ६ । १ । १४८ । कुत्सितं वचो वर्चस्कमन्नमलम् । तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । 'वर्चस्के' किम् । अवकरः ।

१०६४ । अपस्करो रथाङ्गम् । ६ । १ । १४९ । अपकरोऽन्यः ।

१०६५ । विष्किरः शकुनौ वा । ६ । १ । १५० । पक्षे विकिरः । वावचनेनैव सुड्विकल्पसिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूदिति वृत्तिस्तत्र । भाष्यविरोधात् ।

१०६६ । प्रतिष्कशश्च कशेः । ६ । १ । १५२ । 'कश गतिशासनयोः' इत्यस्मात् पूर्वस्य पचाद्यचि सुट् निपात्यते । षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । 'कशेः' किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा, तथापि कशेर्धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ।

१०६७ । प्रस्कण्वहरिश्चन्द्रावृषी । ६ । १ । १५३ । हरिश्चन्द्रग्रहणममन्त्रार्थम् । 'ऋषी' इति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ।

१०६८ । मस्करमस्करिणौ वेणुपरिव्राजकयोः । ६ । १ । १५४ । मकारशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । 'वेणु–' इति किम् । मकरो ग्राहः । मकरी समुद्रः ।

१०६९ । कास्तीराजस्तुन्दे नगरे । ६ । १ । १५५ । ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । 'नगरे' किम् । कातीरम् । अजतुन्दम् ।

१०७० । कारस्करो वृक्षः । ६ । १ । १५६ । (ग १५२) । कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति, न सूत्रेषु ।

१०७१ । पारस्करप्रभृतीनि च संज्ञायाम् । ६ । १ । १५७ । एतानि ससुट्कानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा । 'तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च' (वा ३७९३) । तात्पूर्वं चत्वेन दकारो बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपत्योः सुट् । 'चौरदेवतयोः' इति समुदायोपाधिः । तस्करः । बृहस्पतिः । 'प्रायस्य चित्तिचित्तयोः' (वा ३७९४) । प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ।

इति समासाश्रयविधिप्रकरणम् ।

---

१ केचित्त्विति । अत्रारुचिबीजं पारस्करादिषु प्रत्यक्षतो दर्शनम्, प्रकरणाद्विसर्गस्थाने तेन सत्वविधानं च । न सूत्रेष्विति । न गणसूत्रेषु इत्यर्थः । एवं च पारस्कराद्यन्तर्गणसूत्रे बोध्यम् इति शेखरः । अयं च 'कस्कादिषु' इति क्वाचित्कं पाठमाश्रित्य । वस्तुतस्तु 'पारस्करादिषु' इति पाठः । मूलसंदर्भस्वारस्यात् । काशिकासंवादाच्च ।

अथ तद्धितापत्याधिकारप्रकरणम्।

१०७२। समर्थानां प्रथमाद्वा। ४। १। ८२। इदं पदत्रयमधिक्रियते। 'प्राग्दिशः–' (सू १९४७) इति यावत्। सामर्थ्यं परिनिष्ठितत्वम्। कृतसंधिकार्यत्वमिति यावत्।

१०७३। प्राग्दीव्यतोऽण्। ४। १। ८३। 'तेन दीव्यति–' (सू १५५०) इत्यतः प्रागणधिक्रियते।

१०७४। अश्वपत्यादिभ्यश्च। ४। १। ८४। एभ्योऽण्स्यात्प्राग्दीव्यतीयेष्वर्थेषु। वक्ष्यमाणस्य ण्यस्यापवादः।

१०७५। तद्धितेष्वचामादेः। ७। २। ११७। ञिति णिति च तद्धिते परेऽचामादेरचो वृद्धिः स्यात्।

१०७६। किति च। ७। २। ११८। किति तद्धिते च तथा। अश्वपतेरपत्यादाश्वपतम्। गाणपतम्। 'गाणपत्यो मन्त्रः' इति तु प्रामादिकमेव।

१०७७। दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः। ४। १। ८५। दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः। दैत्यः। अदितेरादित्यस्य वादित्यः। प्राजापत्यः। 'यमाच्च' इति काशिकायाम्। याम्यः। 'पृथिव्या ञाञौ' (वा २५५४)। पार्थिवा–पार्थिवी। 'देवाद्यञञौ' (वा २५५५)। दैव्यम्–दैवम्। 'बहिषष्टिलोपो यञ्च' (वा २५५६)। बाह्यः। 'ईकक्च' (वा २५५७)। बाहीकः। 'स्थाम्नोऽकारः' (वा २५५९)। अश्वत्थामः। पृषोदरादित्वात्सस्य तः। 'भवार्थे तु लुग्वाच्यः' (वा २८८२)। अश्वत्थामा। 'लोम्नोऽपत्येषु बहुष्वकारः' (वा २५६०)। बाह्वादीञोऽपवादः। उडुलोमाः। उडुलोमान्। 'बहुषु' किम्। औडुलोमिः। 'गोरजादिप्रसङ्गे यत्' (वा २५६१)। गव्यम्। 'अजादिप्रसङ्गे' किम्। गोभ्यो हेतुभ्य आगतं गोरूप्यम्। गोमयम्।

१०७८। उत्सादिभ्योऽञ्। ४। १। ८६। औत्सः। 'अग्निकलिभ्यां ढग्वक्तव्यः' (वा २६८९)। अग्नेरपत्याद्याग्नेयम्। कालेयम्।

इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः।

१०७९। स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्। ४। १। ८७। 'धान्यानां भवने–' (सू १८०२) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः। स्त्रैणः। पौंस्नः। 'वत्यर्थे न'। 'स्त्री पुंवच्च' (सू ९३२) इति ज्ञापकात्। स्त्रीवत्। पुंवत्।

१०८०। द्विगोर्लुगनपत्ये। ४। १। ८८। द्विगोर्निमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात्। पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। 'द्विगोर्निमित्तस्य' इति किम्। पञ्चकपालस्येदं खण्डं पाञ्चकपालम्। 'अजादिः' किम्। पञ्चगर्गरूप्यम्। 'अनपत्ये' किम्। द्वयोर्मित्रयोरपत्यं द्वैमैत्रिः।

१०८१। गोत्रेऽलुगचि। ४। १। ८९। अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुक्स्यात्। गर्गाणां छात्राः। 'वृद्धाच्छः' (सू १३३७)।

१०८२। आपत्यस्य च तद्धितेऽनाति। ६। ४। १५१। हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे। गार्गीयाः। 'प्राग्दीव्यतीये' किम्। गर्गेभ्यो हितं गर्गीयम्। 'अचि' किम्। गर्गेभ्य आगतं गर्गरूप्यम्।

१०८३ । यूनि लुक् । ४ । १ । ९० । प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते युव त्ययस्य लुक्स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । वक्ष्यमाणः फिन् । ततो यून्यण् ग्लुचुकायनः । तस्य छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ।

१०८४ । पैलादिभ्यश्च । २ । ४ । ५९ । एभ्यो युवप्रत्ययस्य लुक् । 'पीलाया वा' (सू ११२१) इत्यण् । तस्मात् 'अणो द्व्यचः' (सू ११८०) इति फिञ् । तस्य लुक् । पैलः पिता पुत्रश्च । 'तद्राजाच्चाणः' (ग २१) । द्व्यञ्मगधेत्यण्णन्तादाङ्गशब्दात् 'अणो द्व्यचः' (सू ११८०) इति फिञो लुक् । आङ्गः पिता पुत्रश्च ।

१०८५ । इञः प्राचाम् । २ । ४ । ६० । गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात् तच्चेद्गोत्रं प्राचां भवति । पन्नागारस्यापत्यम् । 'अत इञ्' (सू १०९५) 'यञिञोश्च' (सू ११० इति फक् । पान्नागारिः पिता पुत्रश्च । 'प्राचाम्' किम् । दाक्षिः पिता । दाक्षायणः पुत्रः ।

१०८६ । न तौल्वलिभ्यः । २ । ४ । ६१ । तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लु स्यात । पूर्वेण प्राप्तः । तुल्वलः । तत इञि फक् । तौल्वलिः पिता । तौल्वलायनः पुत्रः ।

१०८७ । फक्फिञोरन्यतरस्याम् । ४ । १ । ९१ । 'यूनि लुक्–' (सू १०८३) इति नित्ये लुकि प्राप्ते विकल्पार्थं सूत्रम् । कात्यायनस्य छात्राः कातीयाः–कात्यायनीयाः । यस्क स्यापत्यं यास्कः । शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । 'अणो द्व्यचः–' (सू ११८ इति फिञ् । तस्य छात्रा यास्कीयाः–यास्कायनीयाः ।

१०८८ । तस्यापत्यम् । ४ । १ । ९२ । षष्ठ्यन्तात्कृतसंधेः समर्थादपत्येऽर्थे उक्ता क्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यमौपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ।

'तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् ।
उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥' (वा २५८३–२५८४)

योगविभागस्तु । भानोरपत्यं भानवः । 'कृतसंधेः' किम् । सौत्थितिः । अकृतव्यूहपरिभा सावुत्थितिर्मा भूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । 'प्रथमात्' कि अपत्यवाचकात्षष्ठ्यर्थे मा भूत् । वाग्रहणाद्वाक्यमपि । 'दैवयज्ञि–' (सू १२०१) इति सूत्रा न्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान्ङीष् । औपगवी । आश्वपत दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ।

१०८९ । अपत्यं पौत्रप्रभृति गोत्रम् । ४ । १ । १६२ । अपत्यत्वेन विवक्षितं पौत्र गोत्रसंज्ञं स्यात् ।

१०९० । जीवति तु वंश्ये युवा । ४ । १ । १६३ । वंश्ये पित्रादौ जीवति पौत्रादे दपत्यं चतुर्थादि तद्युवसंज्ञमेव न तु गोत्रसंज्ञम् ।

१०९१ । भ्रातरि च ज्यायसि । ४ । १ । १६४ । ज्येष्ठे भ्रातरि जीवति कनीयां तुर्थादिर्युवसंज्ञश्च स्यात् ।

१०९२ । वान्यस्मिन्सपिण्डे स्थविरतरे जीवति । ४ । १ । १६५ । भ्रा रन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । जीवतिग्रहणमपत्यस्य विशेषणम् । द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहभ्रातरि वा जीवति । गार्ग्यस्यापत्यं गार्ग्यायणः–गा

वा। 'स्थविर–' इति किम्। स्थानवयोन्यूने गार्ग्य एव। 'जीवति' इति किम्। मृते मृतो वा गार्ग्य एव। 'वृद्धस्य च पूजायामिति वाच्यम्' (वा २६५४)। गोत्रस्यैव वृद्धसंज्ञा प्राचाम्। गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम्। तत्रभवान्गार्ग्यायणः। 'पूजा–' इति किम्। गार्ग्यः। 'यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम्' (वा २६५१)। गार्ग्यो जाल्मः। 'कुत्सा–' इति किम्। गार्ग्यायणः।

१०९३। एको गोत्रे। ४। १। ९३। गोत्र एक एवापत्यप्रत्ययः स्यात्। उपगो-र्गोत्रापत्यमौपगवः। गार्ग्यः। नाडायनः।

गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा।
यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते॥
अपत्यं पितुरेव स्यात्ततः प्राचामपीति च।
मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम्॥

पितुरेवापत्यमिति पक्षे ह्युपगोस्तृतीये वाच्य औपगवादिञ्स्यात्। चतुर्थे त्वजीवज्ज्येष्ठे मृत-वंश्य औपगवेः फक्। इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्र एकोनशतं प्रत्ययाः स्युः। पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्य उपगोरणा इष्टे सिद्धेऽप्यणण्णन्ता-दिञपि स्यात्। चतुर्थे फगिति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतेरनिष्टप्रत्ययाः स्युः। अतो नियमार्थमिदं सूत्रम्। एवमुत्तरसूत्रेऽप्यूह्यम्।

१०९४। गोत्राद्यून्यस्त्रियाम्। ४। १। ९४। यून्यपत्ये गोत्रप्रत्ययान्तादेवापत्यप्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा। गर्गस्य युवापत्यं गार्ग्यायणः। स्त्रियां गोत्रत्वादेक एव प्रत्ययः।

१०९५। अत इञ्। ४। १। ९५। अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादि-ञ्स्यादपत्येऽर्थे। दाक्षिः।

१०९६। बाह्वादिभ्यश्च। ४। १। ९६। बाहविः। औडुलोमिः। आकृतिगणोऽयम्।

१०९७। सुधातुरकङ् च। ४। १। ९७। चादिञ्। सुधातुरपत्यं सौधातकिः। 'व्यास-वरुडनिषादचाण्डालबिम्बानां चेति वक्तव्यम्' (वा २६११)।

१०९८। न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्। ७। ३। ३। पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः। किं तु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः। वैयासकिः। वारुडकिरित्यादि।

१०९९। गोत्रे कुञ्जादिभ्यश्च्फञ्। ४। १। ९८।

११००। व्रातच्फञोरस्त्रियाम्। ५। ३। ११३। व्रातवाचिभ्यश्च्फञन्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम्। कौञ्जायन्यः। बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते। ब्राध्नायन्यः। स्त्रियां कौञ्जा-यनी। गोत्रत्वे न जातित्वान्ङीष्। अनन्तरापत्ये कौञ्जिः।

११०१। नडादिभ्यः फक्। ४। १। ९९। 'गोत्रे' इत्येव नाडायनः। चारायणः। अनन्तरो नाडिः।

११०२। हरितादिभ्योऽञः। ४। १। १००। एभ्योऽञन्तेभ्यो यूनि फक्। हारिता-यनः। इह गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम्। न हि गोत्रादपरो गोत्रप्रत्ययः। बिदाद्यन्त-र्गणो हरितादिः।

११०३। यञिञोश्च। ४। १। १०१। गोत्रे यौ यञिञौ तदन्तात्फक्स्यात्। 'अना...
इत्युक्तेः 'आपत्यस्य–' (सू १०८२) इति यलोपो न। गार्ग्यायणः। दाक्षायणः।

११०४। शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु। ४। १। १०२। गोत्रे फक्। या...
ञोरपवादः। आद्यौ बिदादी। शारद्वतायनो भार्गवश्चेत्। शारद्वतोऽन्यः। शौनकायनो वात्स्य...
श्चेत्। शौनकोऽन्यः। दार्भायण आग्रायणश्चेत्। दार्भिरन्यः।

११०५। द्रोणपर्वतजीवन्तादन्यतरस्याम्। ४। १। १०३। एभ्यो गोत्रे फग्वा। द्रौणा...
यणः–द्रौणिः। पार्वतायनः–पार्वतिः। जैवन्तायनः–जैवन्तिः। अनादिरिह द्रोणः। अश्वत्था...
म्न्यनन्तरे तूपचारात्।

११०६। अनृष्यानन्तर्ये बिदादिभ्योऽञ्। ४। १। १०४। एभ्योऽञ्गोत्रे, ये त्व...
नृषयः पुत्रादयस्तेभ्य आनन्तर्ये। सूत्रे स्वार्थे ष्यञ्। बिदस्य गोत्रापत्यं बैदः। अनन्त...
बैदिः। बाह्वादेराकृतिगणत्वादिञ्। पुत्रस्यापत्यं पौत्रः। दौहित्रः।

११०७। गर्गादिभ्यो यञ्। ४। १। १०५। 'गोत्रे' इत्येव। गार्ग्यः। वात्स्यः।

११०८। यञञोश्च। २। ४। ६४। गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक्स्या...
त्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः। बिदाः। उर्वाः। 'तत्कृते' इति किम्।
प्रियगार्ग्यः। स्त्रियां तु गार्ग्यः स्त्रियः। 'गोत्रे' किम्। द्वैप्याः। औत्साः। प्रवराध्यायप्रसि...
द्धमिह गोत्रम्। तेनेह न। पौत्राः। दौहित्राः।

११०९। मधुबभ्र्वोर्ब्राह्मणकौशिकयोः। ४। १। १०६। गोत्रे यञ्। माधव्यो
ब्राह्मणः। माधवोऽन्यः। बाभ्रव्यः कौशिकर्षिः। बाभ्रवोऽन्यः। बभ्रुशब्दस्य गर्गादि...
पाठात्सिद्धेऽपि नियमार्थमिदम्। गर्गादिपाठफलं तु लोहितादिकार्यम्। बाभ्रव्यायणी।

१११०। कपिबोधादाङ्गिरसे। ४। १। १०७। गोत्रे यञ्स्यात्। काप्यः। बौध्यः।
'आङ्गिरसे' किम्। कापेयः। बौधिः।

११११। वतण्डाच्च। ४। १। १०८। 'आङ्गिरसे' इत्येव। वातण्ड्यः। अनाङ्गिरसे
तु गर्गादौ शिवादौ च पाठाद्यञणौ। वतण्डचः–वातण्डः।

१११२। लुक्स्त्रियाम्। ४। १। १०९। 'वतण्डाच्च' (सू ११११) इति विहित...
लुक्स्यात्स्त्रियाम्। शार्ङ्गरवादित्वान्ङीन्। वतण्डी। अनाङ्गिरसे तु वातण्ड्यायनी। लोहि...
तादित्वात्ष्फः। अणि तु वातण्डी। ऋषित्वाद्वक्ष्यमाणः ष्यङ् न।

१११३। अश्वादिभ्यः फञ्। ४। १। ११०। गोत्रे। आश्वायनः। 'पुंसि जा...
(ग सू ६९)। पुंसीति तु प्रकृतिविशेषणम्। जातस्य गोत्रापत्यं जातायनः। 'पुंसि'
किम्। जाताया अपत्यं जातेयः।

१११४। भर्गात्त्रैगर्ते। ४। १। १११। गोत्रे फञ्। भार्गायणस्त्रैगर्तः। भार्गिरन्यः।

१११५। शिवादिभ्योऽण्। ४। १। ११२। 'गोत्रे' इति निवृत्तम्। शिवस्यापत्यं शैवः।
गाङ्गः। पक्षे तिकादित्वात्फिञ्। गाङ्गायनिः। शुभ्रादित्वाड्ढक्। गाङ्गेयः।

१११६। अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः। ४। १। ११३। अवृद्धा...
नदीमानुषीनामभ्योऽण्स्यात्। ढकोऽपवादः। यामुनः। नार्मदः। चिन्तिताया अपत्यं चैन्तितः

'अवृद्धाभ्यः' किम्। वासवदत्तेयः। 'नदी–' इत्यादि किम्। वैनतेयः। 'तन्नामिकाभ्यः' किम्। शोभनाया अपत्यं शौभनेयः।

११९७। ऋष्यन्धकवृष्णिकुरुभ्यश्च। ४। १। ११४। ऋषयो मन्त्रद्रष्टारः। वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः। श्वाफल्कः। वृष्णिभ्यः। वासुदेवः। आनिरुद्धः। 'शौरिः' इति तु बाह्वादित्वादिञ्। कुरुभ्यः। नाकुलः। साहदेवः। इञ एवायमपवादो मध्येऽपवादन्यायात्। अत्रिशब्दात्तु परत्वाड्ढक्। आत्रेयः।

१११८। मातुरुत्संख्यासंभद्रपूर्वायाः। ४। १। ११५। संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः। आदेशार्थं वचनम्। प्रत्ययस्तूत्सर्गेण सिद्धः। स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः। तेन धान्यमातुर्न। 'संख्या–' इति किम्। सौमात्रः। शुभ्रादित्वाद्द्वैमात्रेयः।

१११९। कन्यायाः कनीन च। ४। १। ११६। ढकोऽपवादोऽण्। तत्संनियोगेन कनीनादेशश्च। कानीनो व्यासः कर्णश्च। अनूढाया एवापत्यमित्यर्थः।

११२०। विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु। ४। १। ११७। अपत्येऽण्। वैकर्णो वात्स्यः। वैकर्णिरन्यः। शौङ्गो भारद्वाजः। शौङ्गिरन्यः। छागल आत्रेयः। छागलिरन्यः। केचित्तु 'शुङ्गा' इत्यावन्तं पठन्ति। तेषां ढक्प्रत्युदाहरणम्। शौङ्गेयः।

११२१। पीलाया वा। ४। १। ११८। तन्नामिकाणं बाधित्वा 'द्व्यचः' (सू ११२४) इति ढकि प्राप्ते पक्षेऽण्विधीयते। पीलाया अपत्यं पैलः–पैलेयः।

११२२। ढक्च मण्डूकात्। ४। १। ११९। चादण्। पक्षे इञ्। माण्डूकेयः–माण्डूकः–माण्डूकिः।

११२३। स्त्रीभ्यो ढक्। ४। १। १२०। स्त्रीप्रत्ययान्तेभ्यो ढक्स्यात्। वैनतेयः। बाह्वादित्वात्सौमित्रिः। शिवादित्वात्सापत्नः।

११२४। द्व्यचः। ४। १। १२१। द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक्। तन्नामिकाणोऽपवादः। दात्तेयः। पार्थ इत्यत्र तु 'तस्येदम्' (सू १५००) इत्यण्।

११२५। इतश्चानिञः। ४। १। १२२। इकारान्ताद्व्यचोऽपत्ये ढक्स्यात्। न त्विञन्तात्। दौलेयः। नैधेयः।

११२६। शुभ्रादिभ्यश्च। ४। १। १२३। ढक्स्यात्। शुभ्रस्यापत्यं शौभ्रेयः।

११२७। विकर्णकुषीतकात्काश्यपे। ४। १। १२४। अपत्ये ढक्। वैकर्णेयः। कौषीतकेयः। अन्यो वैकर्णिः। कौषीतकिः।

११२८। भ्रुवो वुक्च। ४। १। १२५। चाड्ढक्। भ्रौवेयः।

११२९। प्रवाहणस्य ढे। ७। ३। २८। प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वपदस्य तु वा ढे परे। प्रवाहणस्यापत्यं प्रावाहणेयः–प्रवाहणेयः।

११३०। तत्प्रत्ययस्य च। ७। ३। २९। ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा। प्रवाहणेयस्यापत्यं प्रावाहणेयिः–प्रवाहणेयिः। वाह्यतद्धितनिमित्ता वृद्धिर्द्वाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः।

११३१। कल्याण्यादीनामिनङ् । ४ । १ । १२६ । एषामिनङादेशः स्यात्, ढक्
काल्याणिनेयः। बान्धकिनेयः।

११३२। कुलटाया वा । ४ । १ । १२७ । इनङ्मात्रं विकल्प्यते । ढक्तु नित्यः
णैव । कौलटिनेयः–कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थं कुलान्यटति
तस्याः 'क्षुद्राभ्यो वा' (सू ११३७) इति पक्षे ढ्रक् । कौलटेरः ।

११३३। हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । ७ । ३ । १९ । हृदाद्यन्ते पूर्वोत्तरपदयोः
मादेरचो वृद्धिर्ञिति णिति किति च। सुहृदोऽपत्यं सौहार्दः। सुभगाया अपत्यं सौभागिनेयः
सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः। तेषु भवः साक्तुसैन्धवः ।

११३४। चटकाया ऐरक् ।४।१।१२८। 'चटकस्येति वाच्यम्' (वा २६२४)।लिङ्ग
विशिष्टपरिभाषया स्त्रिया अपि। चटकस्य चटकाया वापत्यं चाटकैरः। 'स्त्रियामपत्ये लुक्
कव्यः' (वा २६२५)। तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ।

११३५। गोधाया ढ्रक् । ४ । १ । १२९ । गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः।

११३६। आरगुदीचाम् । ४ । १ । १३० । गौधारः। रका सिद्ध आकारोच्चारणम
विधानार्थम् । जडस्यापत्यं जाडारः। पण्डस्यापत्यं पाण्डारः।

११३७। क्षुद्राभ्यो वा । ४ । १ । १३१ । अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ्रक्
पक्षे ढक् । काणेरः–काणेयः । दासेरः–दासेयः ।

११३८। पितृष्वसुश्छण् । ४ । १ । १३२ । अणोऽपवादः । पैतृष्वस्रीयः ।

११३९। ढकि लोपः । ४ । १ । १३३ । पितृष्वसुरन्तलोपः स्याड्ढकि । अत एव ज्ञापका
काड्ढक् । पैतृष्वसेयः ।

११४०। मातृष्वसुश्च । ४ । १ । १३४ । पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्व
स्रीयः–मातृष्वसेयः ।

११४१। चतुष्पाद्भ्यो ढञ् । ४ । १ । १३५ ।

११४२। ढे लोपोऽकद्र्वाः । ६ । ४ । १४७ । कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे
परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ।

११४३। गृष्ट्यादिभ्यश्च । ४ । १ । १३६ । एभ्यो ढञ्स्यात् । अण्ढकोरपवादः
गार्ष्टेयः । मित्रयोरपत्यम् । ऋष्याणि प्राप्ते ढञ् ।

११४४। केकयमित्त्रयुप्रलयानां यादेरियः । ७ । ३ । २ । एषां यकारादेरियादेशः
स्यात् । ञिति णिति किति च तद्धिते परे । इति यादेशे प्राप्ते ।

११४५। दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्य
धैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि । ६ । ४ । १७४ । एतानि निपात्यन्ते ।
युलोपः । मैत्रेयः । मैत्रेयौ ।

११४६। यस्कादिभ्यो गोत्रे । २ । ४ । ६३ । एभ्योऽपत्यप्रत्ययस्य लुक्स्यात्
बहुत्वे । न तु स्त्रियाम् । मित्रयवः ।

११४७। अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । २ । ४ । ६५ । एभ्यो गोत्र

यस्य लुक्स्यात्तत्कृते बहुत्वे। न तु स्त्रियाम्। अत्रयः। भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः।

११४८। बह्वच इञः प्राच्यभरतेषु। २। ४। ६६। बह्वचः परो य इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात्। पन्नागाराः। युधिष्ठिराः।

११४९। न गोपवनादिभ्यः। २। ४। ६७। एभ्यो गोत्रप्रत्ययस्य लुग्न स्यात्। बिदाद्यन्तर्गणोऽयम्। गौपवनाः। शैग्रवाः।

११५०। तिककितवादिभ्यो द्वन्द्वे। २। ४। ६८। एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक्स्याद्द्वन्द्वे। तैकायनश्च कैतवायनश्च। 'तिकादिभ्यः फिञ्' (सू ११७८)। तस्य लुक्। तिककितवाः।

११५१। उपकादिभ्योऽन्यतरस्यामद्वन्द्वे। २। ४। ६९। एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्याद्द्वन्द्वे चाद्वन्द्वे च। औपकायनाश्च लामकायनाश्च। 'नडादिभ्यः फक्' (सू ११०१)। तस्य लुक्। उपकलमकाः–औपकायनलामकायनाः। भ्राष्टककापिष्ठलाः–भ्राष्टकिकापिष्ठलयः। उपकाः–औपकाः। लमकाः–लामकाः।

११५२। आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्। २। ४। ७०। एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक्स्यात्। अवशिष्टस्य प्रकृतिभागस्य यथासंख्यम् 'अगस्ति' 'कुण्डिनच्' एतावादेशौ स्तः। अगस्तयः। कुण्डिनाः।

११५३। राजश्वशुराद्यत्। ४। १। १३७। 'राज्ञो जातावेवेति वाच्यम्' (वा २६२७)।

११५४। ये चाभावकर्मणोः। ६। ४। १६८। यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणोः। राजन्यः। श्वशुर्यः। जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः।

११५५। अन्। ६। ४। १६७। अणि अन्प्रकृत्या स्यादिति टिलोपो न। 'अभावकर्मणोः' किम्। राज्ञः कर्म भावो वा राज्यम्।

११५६। संयोगादिश्च। ६। ४। १६६। इन्प्रकृत्या स्यादणि परे। चक्रिणोऽपत्यं चाक्रिणः।

११५७। न मपूर्वोऽपत्येऽवर्मणः। ६। ४। १७०। मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि। भाद्रसामः। 'मपूर्वः' किम्। सौत्वनः। 'अपत्ये' किम्। चर्मणा परिवृतश्चार्मणो रथः। 'अवर्मणः' किम्। चक्रवर्मणोऽपत्यं चाक्रवर्मणः। 'वा हितनाम्न इति वाच्यम्' (वा ४२१९)। हितनाम्नोऽपत्यं हैतनामः–हैतनामनः।

११५८। ब्राह्मोऽजातौ। ६। ४। १७१। योगविभागोऽत्र कर्तव्यः। 'ब्राह्मः' इति निपात्यतेऽनपत्येऽणि। ब्राह्मं हविः। ततो जातौ। अपत्ये जातावणि ब्रह्मणष्टिलोपो न स्यात्। ब्रह्मणोऽपत्यं ब्राह्मणः। 'अपत्ये' किम्। ब्राह्मी औषधिः।

११५९। औक्षमनपत्ये। ६। ४। १७३। अणि टिलोपो निपात्यते। औक्षं पदम्। 'अनपत्ये' किम्। उक्ष्णोऽपत्यमौक्ष्णः।

११६०। षपूर्वहन्धृतराज्ञामणि। ६। ४। १३५। षपूर्वो योऽन्तस्य हनादेश्च भस्यातो लोपोऽणि। औक्ष्णः। ताक्ष्णः। भ्रौणघ्नः। धृतराज्ञोऽपत्यं धार्तराज्ञः। 'षपूर्व–' इति किम्। साम्नोऽपत्यं सामनः। 'अणि' किम्। ताक्षण्यः।

११६१ । क्षत्राद्धः । ४ । १ । १३८ । क्षत्रियः । 'जातौ' इत्येव । क्षात्रिरन्यः ।

११६२ । कुलात्खः । ४ । १ । १३९ । कुलीनः । तदन्तादपि । उत्तरसूत्रे 'अपूर्वपद' इति लिङ्गात् । आढ्यकुलीनः ।

११६३ । अपूर्वपदादन्यतरस्यां यड्ढकञौ । ४ । १ । १४० । 'कुलात्' इत्येव । प... खः । कुल्यः–कौलेयकः–कुलीनः । 'पद'ग्रहणं किम् । बहुकुल्यः–बाहुकुलेयकः–बहुकुलीनः

११६४ । महाकुलादञ्खञौ । ४ । १ । १४१ । 'अन्यतरस्याम्' इत्यनुवर्तते । पक्षे ख... माहाकुलः–माहाकुलीनः–महाकुलीनः ।

११६५ । दुष्कुलाड्ढक् । ४ । १ । १४२ । पूर्ववत्पक्षे खः । दौष्कुलेयः–दुष्कुलीनः

११६६ । स्वसुश्छः । ४ । १ । १४३ । स्वस्रीयः ।

११६७ । भ्रातुर्व्यच्च । ४ । १ । १४४ । चाच्छः । अणोऽपवादः । भ्रातृव्यः–भ्रात्रीयः

११६८ । व्यन्सपत्ने । ४ । १ । १४५ । भ्रातुर्व्यन्स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन श... वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ।

११६९ । रेवत्यादिभ्यष्ठक् । ४ । १ । १४६ ।

११७० । ठस्येकः । ७ । ३ । ५० । अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः

११७१ । गोत्रस्त्रियाः कुत्सने ण च । ४ । १ । १४७ । गोत्रं या स्त्री तद्वाचका... ब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः–गार्गिको वा जाल्मः 'भस्याढे तद्धिते' इति पुंवद्भावाद्गार्ग्यशब्दाण्णठकौ । 'यस्य–' (सू ३११) इति लोपः 'आपत्यस्य–' (सू १०८२) इति यलोपः ।

११७२ । वृद्धाट्ठक्सौवीरेषु बहुलम् । ४ । १ । १४८ । सुवीरदेशोद्भवाः सौवीराः । वृ... त्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः–भागवित्तिकः । पक्षे फक् । भा... वित्तायनः ।

११७३ । फेश्छ च । ४ । १ । १४९ । फिञन्तात्सौवीरगोत्रादपत्ये छः, ठक्च कु... गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्वात्फिञ् । तस्यापत्यं यामुन्दायनीयः–यामु... यनिकः । 'कुत्सने' किम् । यामुन्दायनिः । औत्सर्गिकस्याणो 'ण्यक्षत्रिया–' (सू १२७६)... लुक् । 'सौवीर–'इति किम् । तैकायनिः ।

११७४ । फाण्टाहृतिमिमताभ्यां णफिञौ । ४ । १ । १५० । सौवीरेषु । 'नेह यथा... ख्यम् 'अल्पाच्तरस्य परनिपाताल्लिङ्गात्' इति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति ... तम् । फाण्टाहृतः–फाण्टाहृतायनिः । मैमतः–मैमतायनिः ।

११७५ । कुर्वादिभ्यो ण्यः । ४ । १ । १५१ । अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्... 'सम्राजः क्षत्रिये' (ग सू ७५) । साम्राज्यः–साम्राजोऽन्यः ।

११७६ । सेनान्तलक्षणकारिभ्यश्च । ४ । १ । १५२ । एभ्यो ण्यः । 'एति संज्ञाया... (सू १०२३) इति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात्तान्तुवा... कौम्भकार्यः । नापित्यः ।

११७७ । उदीचामिञ् । ४ । १ । १५३ । हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौ...

कारिः । नापितात्तु परत्वात्फिञेव । नापितायनिः । 'तक्ष्णोऽण उपसंख्यानम्' (वा २५४०)। 'वपूर्व-'(सू ११६०) इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्ष्ण्यः ।

११७८ । तिकादिभ्यः फिञ् । ४ । १ । १५४ । तैकायनिः ।

११७९ । कौशल्यकार्मार्याभ्यां च । ४ । १ । १५५ । अपत्ये फिञ् । इञोऽपवादः । परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कुशलस्यापत्यं कौशल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः । 'छागवृषयोरपि' (वा २६४३) । छाग्यायनिः । वार्ष्यायणिः ।

११८० । अणो द्व्यचः । ४ । १ । १५६ । अपत्ये फिञ् । इञोऽपवादः । कार्त्र्यायणिः । 'अणः' इति किम् । दाक्षायणः । 'द्व्यचः' किम् । औपगविः । 'त्यदादीनां फिञ्वा वाच्यः' (वा ५०५०) । त्यादायनिः-त्यादः ।

११८१ । उदीचां वृद्धादगोत्रात् । ४ । १ । १५७ । आम्रगुप्तायनिः । प्राचां तु आम्रगुप्तिः । 'वृद्धात्' किम् । दाक्षिः । 'अगोत्रात्' किम् । औपगविः ।

११८२ । वाकिनादीनां कुक्च । ४ । १ । १५८ । अपत्ये फिञ्वा । वाकिनस्यापत्यं वाकिनकायनिः-वाकिनिः ।

११८३ । पुत्रान्तादन्यतरस्याम् । ४ । १ । १५९ । अस्माद्वा फिञ्सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रकायणिः-गार्गीपुत्रायणिः-गार्गीपुत्रिः ।

११८४ । प्राचामवृद्धात्फिन्बहुलम् । ४ । १ । १६० । ग्लुचुकायनिः ।

११८५ । मनोर्जातावञ्यतौ षुक्च । ४ । १ । १६१ । समुदायार्थो जातिः । मानुषः-मनुष्यः ।

११८६ । जनपदशब्दात्क्षत्रियादञ् । ४ । १ । १६८ । जनपदक्षत्रिययोर्वाचकादञ्स्यादपत्ये । 'दाण्डिनायन-'(सू ११४५) इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ । 'क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत्' (वा २६६९) । तद्राजमाचक्षाणस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् । पञ्चालानां राजा पाञ्चालः । 'पूरोरण्वक्तव्यः' (वा २६७०) । पौरवः । 'पाण्डोर्ड्यण्' (वा २६७१) । पाण्ड्यः ।

११८७ । साल्वेयगान्धारिभ्यां च । ४ । १ । १६९ । आभ्यामपत्येऽञ् । 'वृद्धेत्-'(सू ११८९) इति ञ्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ।

११८८ । द्व्यञ्मगधकलिङ्गसूरमसादण् । ४ । १ । १७० । अञोऽपवादः । द्व्यच् । आङ्गः । वाङ्गः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ।

११८९ । वृद्धेत्कोसलाजादाञ्ञ्यङ् । ४ । १ । १७१ । वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ।

११९० । कुरुनादिभ्यो ण्यः । ४ । १ । १७२ । कौरव्यः । नैषध्यः । 'स नैषधस्यार्थपतेः' इत्यादौ तु शैषिकोऽण् ।

११९१ । साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् । ४ । १ । १७३ । साल्वो जनप-

---

१ काशिकानुरोध्यप्ययं पाठो व्यर्थ एव । त्यदादीनां वृद्धत्वेन 'उदीचाम्-' इत्युत्तरसूत्रेण रूपद्वयसिद्धेः । भाष्यानुक्तत्वाच्च ।

दस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ।

११९२ । ते तद्राजाः । ४ । १ । १७४ । अञादय एतत्संज्ञाः स्युः ।

११९३ । तद्राजस्य बहुषु तेनैवास्त्रियाम् । २ । ४ । ६२ । बहुष्वर्थेषु तद्राजस्य लुक्स्यात् तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि 'कौरव्याः पशवः' 'तस्यामेव रघोः पाण्ड्याः' इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । 'रघूणामन्वयं वक्ष्ये', 'निरुध्यमाना यदुभिः कथंचित्' इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया

११९४ । कम्बोजाल्लुक् । ४ । १ । १७५ । अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ । 'कम्बोजादिभ्य इति वक्तव्यम्' (वा २६७४) । चोलः । शकः । द्व्यज्लक्षणस्याणो लुक् । केरलः । यवनः । अञो लुक् । 'कम्बोजाः समरे' इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । 'सिन्धुतक्षशिलादिभ्योऽणञौ' (सू १४७२) इत्यण् ।

११९५ । स्त्रियामवन्तिकुन्तिकुरुभ्यश्च । ४ । १ । १७६ । तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ।

११९६ । अतश्च । ४ । १ । १७७ । तद्राजस्याकारस्य स्त्रियां लुक्स्यात् । शूरसेनी । मद्री । कथं 'माद्रीसुतौ' इति । 'ह्रस्व एव पाठः' इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ।

११९७ । न प्राच्यभर्गादियौधेयादिभ्यः । ४ । १ । १७८ । एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मागधी । एते प्राच्याः । भार्गी । कारूशी । कैकयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे ङीष् । 'युधा' 'शुक्रा' आभ्यां 'द्व्यचः' (सू ११ इति ढक् । ततः स्वार्थे 'पर्श्वादियौधेयादिभ्योऽणञौ' (सू २०७०) इत्यञ् । 'शार्ङ्गरवाद्यञः' (सू ५२७) इति ङीन् । 'अतश्च' (सू ११९६) इति लुकि तु ढगन्तत्वान्ङीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ।

११९८ । अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे । ४ । १ । ७८ । त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम्, गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् । 'निर्दिश्यमानस्यादेशा भवन्ति' (प १३) इत्यणिञोरेव षङावितौ । 'यङश्चाप्' (सू ५२८) । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । 'अनार्षयोः' किम् । वासिष्ठी । वैश्वामित्री । 'गुरूपोत्तमयोः' किम् । औपगवी । जातिलक्षणो ङीष् । 'गोत्रे' किम् । अहिच्छत्रे जाता आहिच्छत्री ।

११९९ । गोत्रावयवात् । ४ । १ । ७९ । गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या ।

१२०० । क्रौड्यादिभ्यश्च । ४ । १ । ८० । स्त्रियां ष्यङ्प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिञर्थश्चारम्भः । क्रौड्या । व्याड्या । 'सूत युवत्याम्' (ग सू ९५) सूत्या । 'भोज क्षत्रिये' (ग सू ९६) । भोज्या ।

१२०१ । दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् । ४ ।

८१ । एभ्यश्चतुर्भ्यः ष्यङ् । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे 'इतो मनुष्य-(सू ५२०) इति ङीष् । दैवयज्ञ्या-दैवयज्ञी ।

इति तद्धितापत्याधिकारप्रकरणम् ।

अथ तद्धितचातुरर्थिकप्रकरणम् ।

१२०२ । तेन रक्तं रागात् । ४ । २ । १ । रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । 'रागात्' किम् । देवदत्तेन रक्तं वस्त्रम् ।

१२०३ । लाक्षारोचनाट्ठक् । ४ । २ । २ । लाक्षिकः । रौचनिकः । 'शकलकर्दमाभ्यामुपसंख्यानम्' (वा २६७९) । शाकलिकः । कार्दमिकः । 'आभ्यामणपि' इति वृत्तिकारः । शाकलः । कार्दमः । 'नील्या अन्' (वा २६८०) । नील्या रक्तं नीलम् । 'पीतात्कन्' (वा २६८१) । पीतकम् । 'हरिद्रामहारजनाभ्यामञ्' (वा २६८२) । हारिद्रम् । माहारजनम् ।

१२०४ । नक्षत्रेण युक्तः कालः । ४ । २ । ३ । पुष्येण युक्तं पौषमहः । पौषी रात्रिः ।

१२०५ । लुबविशेषे । ४ । २ । ४ । पूर्वेण विहितस्य लुप्स्यात्षष्टिदण्डात्मककालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि 'पुष्ययुक्ता पौर्णमासी पौषी' इति । 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' (सू १२२५) इति निर्देशेन पौर्णमास्यामयं लुन्नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अत एव लुब्युक्तवद्भावाभावश्च । 'अबाधकान्यपि निपातनानि' । श्रावणी ।

१२०६ । संज्ञायां श्रवणाश्वत्थाभ्याम् । ४ । २ । ५ । विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । 'संज्ञायाम्' किम् । श्रावणी । आश्वत्थी ।

१२०७ । द्वन्द्वाच्छः । ४ । २ । ६ । नक्षत्रद्वन्द्वाद्युक्ते काले छः स्याद्विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ।

१२०८ । दृष्टं साम । ४ । २ । ७ । तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम । 'अस्मिन्नर्थेऽण डिद्वा वक्तव्यः' (वा २६९०) । उशनसा दृष्टमौशनम्-औशनसम् ।

(१२०९) कलेर्ढक्[१] । ४ । २ । ८ । (वा २६८९) । कलिना दृष्टं कालेयं साम ।

१२१० । वामदेवाड्ड्यड्ड्यौ । ४ । २ । ९ । वामदेवेन दृष्टं साम वामदेव्यम् ।

'सिद्धे यस्येति लोपेन किमर्थं ययतौ डितौ ।
ग्रहणं मातदर्थेऽभूद्वामदेव्यस्य नञ्स्वरे ॥' [इति भाष्यम् ।]

१२११ । परिवृतो रथः । ४ । २ । १० । वस्त्रैः परिवृतो वास्त्रो रथः । 'रथः' किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न । छात्रैः परिवृतो रथः ।

१२१२ । पाण्डुकम्बलादिनिः । ४ । २ । ११ । पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ।

---

१ कलेर्ढगिति वार्तिकम्-इति शेखरकृत् ।

१२१३ । द्वैपवैयाघ्रादञ् । ४ । २ । १२ । द्वीपिनो विकारो द्वैपम् । तेन परिवृ॰ द्वैपो रथः । एवं वैयाघ्रः ।

१२१४ । कौमारापूर्ववचने । ४ । २ । १३ । 'कौमार' इत्यविभक्तिको निर्देशः । अ॰ र्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिं कुमारी पतिमुपपन्ना कौमारी भार्या ।

१२१५ । तत्रोद्धृतममत्रेभ्यः । ४ । २ । १४ । शराव उद्धृतः शाराव ओदनः । उद्ध॰ तिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ।

१२१६ । स्थण्डिलाच्छयितरि व्रते । ४ । २ । १५ । 'तत्र' इत्येव । समुदायेन चे॰ गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ।

१२१७ । संस्कृतं भक्षाः । ४ । २ । १६ । सप्तम्यन्तादण्स्यात्संस्कृतेऽर्थे यत्संस्कृ॰ भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृता भ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुरोडाशः ।

१२१८ । शूलोखाद्यत् । ४ । २ । १७ । अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् उखा पात्रविशेषः । तस्यां संस्कृतमुख्यम् ।

१२१९ । दध्नष्ठक् । ४ । २ । १८ । दध्नि संस्कृतं दाधिकम् ।

१२२० । उदश्वितोऽन्यतरस्याम् । ४ । २ । १९ । ठक्स्यात् । पक्षेऽण् ।

१२२१ । इसुसुक्तान्तात्कः । ७ । ३ । ५१ । 'इस्' 'उस्' 'उक्' 'त' एतदन्तान॰ रस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धत इत्युदश्वित् । तत्र संस्कृत औदश्वित्कः—औद॰ श्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आशिषा चरत्याशिषिकः । उषा चरत्यौषिक॰ 'दोष उपसंख्यानम्' (वा ५०५१) । दोर्भ्यां चरति दौष्कः ।[1]

१२२२ । क्षीराड्ढञ् । ४ । २ । २० । अत्र 'संस्कृतम्' इत्येव संबध्यते न तु भक्षा इति तेन यवाग्वामपि भवति । क्षैरेयी ।

१२२३ । सास्मिन्पौर्णमासीति । ४ । २ । २१ । 'इति'शब्दात् 'संज्ञायाम्' इति लभ्य॰ पौषी पौर्णमास्यस्मिन्पौषो मासः ।

१२२४ । आग्रहायण्यश्वत्थाट्ठक् । ४ । २ । २२ । अग्रे हायनमस्या इत्याग्रहायणी प्रज्ञादेराकृतिगणत्वादण् । 'पूर्वपदात्संज्ञायाम्–' (सू ८५७) इति णत्वम् । आग्रहायणी पौ॰ मास्यस्मिन्नाग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमास्यश्वत्थः । निपातनात्पौर्णमास्य॰ मपि लुक् । आश्वत्थिकः ।

१२२५ । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः । ४ । २ । २३ । ए॰ ठग्वा । पक्षेऽण् । फाल्गुनिकः—फाल्गुनो मासः । श्रावणिकः—श्रावणः । कार्तिकिकः—का॰ र्तिकः । चैत्रिकः—चैत्रः ।

१२२६ । सास्य देवता । ४ । २ । २४ । इन्द्रो देवतास्येति ऐन्द्रं हविः । पाशुपतम्

---

१ अत्र च 'अथेह कथं भवितव्यम्–दोर्भ्यां तराति दोष्क इति भवितव्यम्' इति भा॰ मानम् ।

बार्हस्पतम् । त्यज्यमानद्रव्य उद्देश्यविशेषो देवता । मन्त्रः स्तुत्या च । ऐन्द्रो मन्त्रः । 'आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे 'सर्वत्राग्नि-' (वा २६८९) इति ढक् ।

१२२७ । कस्येत् । ४ । २ । २५ । कशब्दस्येदादेशः स्यात्प्रत्ययसंनियोगेन । 'यस्य-' (सू ३११) इति लोपात्परत्वादादिवृद्धिः । को ब्रह्मा देवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ।

१२२८ । शुक्राद्घन् । ४ । २ । २६ । शुक्रियम् ।

१२२९ । अपोनप्त्रपांनप्तृभ्यां घः । ४ । २ । २७ । अपोनप्त्रियम्-अपांनप्त्रियम् । अपोनपात्-अपांनपाच्च देवता । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते-अपांनपातेऽनुब्रूहीति प्रैषः ।

१२३० । छ च । ४ । २ । २८ । योगविभागो यथासंख्यानिवृत्त्यर्थः । अपोनप्त्रीयम्-अपांनप्त्रीयम् । 'शतरुद्राद्घश्च' (वा २७०२) । चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम्-शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्यात् 'द्विगोर्लुगनपत्ये' (सू १०८०) इति न लुक् ।

१२३१ । महेन्द्राद्घाणौ च । ४ । २ । २९ । चाच्छः । महेन्द्रियं हविः-माहेन्द्रम्-माहेन्द्रीयम् ।

१२३२ । सोमाट्ट्यण् । ४ । २ । ३० । सौम्यम् । टित्त्वान्ङीप् । सौमी ऋक् ।

१२३३ । वाय्वृतुपित्रुषसो यत् । ४ । २ । ३१ । वायव्यम् । ऋतव्यम् ।

१२३४ । रीङृतः । ७ । ४ । २७ । अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् । 'यस्येति च' (सू ३११) । पित्र्यम् । उषस्यम् ।

१२३५ । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च । ४ । २ । ३२ । चाद्यत् । द्यावापृथिवीयम्-द्यावापृथिव्यम् । शुनासीरीयम्-शुनासीर्यम् ।

१२३६ । अग्नेर्ढक् । ४ । २ । ३३ । आग्नेयम् ।

१२३७ । कालेभ्यो भववत् । ४ । २ । ३४ । मासिकम् । प्रावृषेण्यम् ।

१२३८ । महाराजप्रोष्ठपदाट्ठञ् । ४ । २ । ३५ । माहाराजिकम् । प्रौष्ठपदिकम् ।

१२३९ । देवताद्वन्द्वे च । ७ । ३ । २१ । अत्र पूर्वोत्तरपदयोरादचो वृद्धिः स्यात्, ञिति णिति किति च परे । आग्निमारुतम् ।

१२४० । नेन्द्रस्य परस्य । ७ । ३ । २२ । परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । 'परस्य' किम् । ऐन्द्राग्नः ।

१२४१ । दीर्घाच्च वरुणस्य । ७ । ३ । २३ । दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । 'दीर्घात्' किम् । 'आग्निवारुणीमनड्वाहीमालभेत' । 'तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम्' (वा २७०६) । नावयज्ञिकः कालः । पाकयज्ञिक· । 'पूर्णमासादण्वक्तव्यः' (वा २७०७) । पूर्णो मासोऽस्यां वर्तत इति पौर्णमासी तिथिः ।

१२४२ । पितृव्यमातुलमातामहपितामहाः । ४ । २ । ३६ । एते निपात्यन्ते । 'पितुर्भ्रातरि व्यत्' (वा २७०८) । पितुर्भ्राता पितृव्यः । 'मातुर्डुलच्' (वा २७०८ । मातुर्भ्राता मातुलः । 'मातृपितृभ्यां पितरि डामहच्' (वा २७०९) । मातुः पिता मातामहः । पितुः पिता पितामहः । 'मातरि षिच्च' (वा २७१०) । मातामही । पितामही । 'अवेर्दुग्धे सोढदूसमरीसचो

वक्तव्याः' (वा २७१२)। सकारपाठसामर्थ्यान्न षः। अविसोढम्। आविदूसम्। अविमरीसम्। 'तिलान्निष्फलात्पिञ्जपेजौ' (वा २७१३)। तिलपिञ्जः। तिलपेजः। वन्ध्यास्तिल इत्यर्थः। 'पिञ्जश्छन्दसि डिच्च' (वा २७१४)। तिल्पिञ्जः।

१२४३। तस्य समूहः। ४। २। ३७। काकानां समूहः काकम्। बाकम्।

१२४४। भिक्षादिभ्योऽण्। ४। २। ३८। भिक्षाणां समूहो भैक्षम्। गर्भिणीनां समूहो गार्भिणम्। इह 'भस्याढे—' इति पुंवद्भावे कृते।

१२४५। इनण्यनपत्ये। ६। ४। १६४। अनपत्यार्थेऽणि परे इन्प्रकृत्या स्यात्। तेन 'नस्तद्धिते' (सू ६७९) इति टिलोपो न। युवतीनां समूहो यौवनम्। शत्रन्तादनुदात्तादेरञि यौवतम्।

१२४६। गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्। ४। २। ३९। एभ्यः समूहे वुञ्स्यात्। लौकिकमिह गोत्रं तच्चापत्यमात्रम्।

१२४७। युवोरनाकौ। ७। १। १। 'यु' 'वु' एतयोरनुनासिकयणोः क्रमात् 'अन' 'अक' एतावादेशौ स्तः। ग्लुचुकायनीनां समूहो ग्लौचुकायनकम्। औक्षकमित्यादि। 'आपत्यस्य च—' (सू १०८२) इति यलोपे प्राप्ते। 'प्रकृत्या अके राजन्यमनुष्ययुवानः' (वा ४२१४)। राजन्यकम्। मानुष्यकम्। 'वृद्धाच्चेति वक्तव्यम्' (वा २७१६)। वार्द्धकम्।

१२४८। केदाराद्यञ्च। ४। २। ४०। चाद्वुञ्। कैदार्यम्—कैदारकम्। 'गणिकाया यञिति वक्तव्यम्' (वा २७१९)। गाणिक्यम्।

१२४९। ठञ्कवचिनश्च। ४। २। ४१। चात्केदारादपि। कवचिनां समूहः कावचिकम्। कैदारिकम्।

१२५०। ब्राह्मणमाणववाडवाद्यत्। ४। २। ४२। ब्राह्मण्यम्। माणव्यम्। वाडव्यम्। 'पृष्ठादुपसंख्यानम्' (वा २७२०)। पृष्ठ्यम्।

१२५१। ग्रामजनबन्धुभ्यस्तल्। ४। २। ४३। ग्रामता। जनता। बन्धुता। 'गजसहायाभ्यां चेति वक्तव्यम्' (वा २७२१)। गजता। सहायता। 'अह्नः खः क्रतौ' (वा २७२२-२७२३)। अहीनः। अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः। 'क्रतौ' किम्। आह्नम्। इह खण्डिकादित्वादञ्। 'अह्नष्टखोरेव' (सू ७८९) इति नियमाट्टिलोपो न। 'पर्श्वा णस् वक्तव्यः' (वा २७२४)।

१२५२। सिति च। १। ४। १६। सिति परे पूर्वं पदसंज्ञं स्यात्। अभत्वादोर्गुणो न। पर्शूनां समूहः पार्श्वम्।

१२५३। अनुदात्तादेरञ्। ४। २। ४४। कापोतम्। मायूरम्।

१२५४। खण्डिकादिभ्यश्च। ४। २। ४५। अञ्स्यात्। खण्डिकानां समूहः खाण्डिकम्।

१२५५। चरणेभ्यो धर्मवत्। ४। २। ४६। काठकम्। छान्दोग्यम्।

१२५६। अचित्तहस्तिधेनोष्ठक्। ४। २। ४७। साक्तुकम्। हास्तिकम्। धैनुकम्।

१२५७। केशाश्वाभ्यां यञ्छावन्यतरस्याम्। ४। २। ४८। पक्षे ठगणौ। कैश्यम्—कैशिकम्। अश्वीयम्—आश्वम्।

१२५८। पाशादिभ्यो यः। ४। २। ४९। पाश्या। तृण्या। धूम्या। वन्या। वात्या।

१२५९ । खलगोरथात् । ४ । २ । ५० । खल्या । गव्या । रथ्या ।

१२६० । इनित्रकट्यचश्च । ४ । २ । ५१ । खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या । 'खलादिभ्य इनिर्वक्तव्यः' (वा २७३५)। डाकिनी। कुटुम्बिनी। आकृतिगणोऽयम्।

१२६१ । विषयो देशे । ४ । २ । ५२ । षष्ठ्यन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । 'देशे' किम् । देवदत्तस्य विषयोऽनुवाकः ।

१२६२ । राजन्यादिभ्यो वुञ् । ४ । २ । ५३ । राजन्यकः ।

१२६३ । भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ । ४ । २ । ५४ । भौरिकीणां विषयो देशः । भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ।

१२६४ । सोऽस्यादिरिति च्छन्दसः प्रगाथेषु । ४ । २ । ५५ । अण् । पङ्क्तिरादिरस्येति पाङ्क्तः प्रगाथः । 'स्वार्थ उपसंख्यानम्' (वा २७४४) । त्रिष्टुबेव त्रैष्टुभम् ।

१२६५ । संग्रामे प्रयोजनयोद्धृभ्यः । ४ । २ । ५६ । 'सोऽस्य' इत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽस्य संग्रामस्य भारतः ।

१२६६ । तदस्यां प्रहरणमिति क्रीडायां णः । ४ । २ । ५७ । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा ।

१२६७ । घञः सास्यां क्रियेति ञः । ४ । २ । ५८ । घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । 'घञः' इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ।

१२६८ । श्येनतिलस्य पाते ञे । ६ । ३ । ७१ । 'श्येन' 'तिल' एतयोर्मुमागमः स्यात् । ञप्रत्ययपरे पातशब्द उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता स्वधा । 'श्येनतिलस्य' किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ।

१२६९ । तदधीते तद्वेद । ४ । २ । ५९ । व्याकरणमधीते वेद वा वैयाकरणः ।

१२७० । क्रतूक्थादिसूत्रान्ताट्ठक् । ४ । २ । ६० । क्रतुविशेषवाचिनामेवेह ग्रहणम् तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वध्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषः । तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा औक्थिकः । 'मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते' । न्यायम्—नैयायिकः । वृत्तिम्—वार्त्तिकः । लोकायतम्—लौकायतिक इत्यादि । 'सूत्रान्तात्त्वकल्पादेरेवेष्यते' (वा २७४४) । सांग्रहसूत्रिकः । 'अकल्पादेः' किम् । काल्पसूत्रः । 'विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम्' (वा २७४४) । वायसविद्यिकः । गौलक्षणिकः । आश्वलक्षणिकः । पाराशरकल्पिकः । 'अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम्' (वा २७४५) । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या । तामधीते वेद वा त्रैविद्यः । 'आख्यानाख्यायिकेतिहासपुराणेभ्यश्च' (वा २७४६) । यवक्रीतमधिकृत्य कृतमाख्यानमुपचाराद्यवक्रीतम् । तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । 'अधिकृत्य कृते ग्रन्थे' (सू १४६७) इत्यर्थे 'वृद्धाच्छः' (सू १३३७) तस्य 'लुबाख्यायिकाभ्यो बहुलम्' इति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः । 'सर्वादेः सादेश्च लुग्वक्तव्यः'

(वा २७४८)। सर्ववेदानधीते सर्ववेदः। सर्वतन्त्रः। सवार्तिकः। 'द्विगोर्लुक्–' (सू १०८ इति लुक्। द्वितन्त्रः। 'इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः' (वा २७४९-२७५०)। पूर्वपदि कः। उत्तरपदिकः। शतपथिकः–शतपथिकी। षष्टिपथिकः–षष्टिपथिकी।

१२७१। क्रमादिभ्यो वुन्। ४। २। ६१। क्रमकः। क्रम पद शिक्षा मीमांसा क्रमादिः।

१२७२। अनुब्राह्मणादिनिः। ४। २। ६२। 'तदधीते तद्वेद' (सू १२६९) इत्यर्थे ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम्। तदधीतेऽनुब्राह्मणी। मत्वर्थीयेनैव सिद्धेऽण्बाधनार्थमिदम्

१२७३। वसन्तादिभ्यष्ठक्। ४। २। ६३। वासन्तिकः। अथर्वाणमधीत आथर्वणिकः। 'दाण्डिनायन–' (सू ११४५) इति सूत्रे निपातनाट्टिलोपो न।

१२७४। प्रोक्ताल्लुक्। ४। २। ६४। प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक्स्यात्। पणनं पणः। 'घञर्थे कविधानम्' इति कः। सोऽस्यास्तीति पणी। तस्य गोत्रापत्यं पाणिनः।

१२७५। गाथिविदथिकेशिगणिपणिनश्च। ६। ४। १६५। एतेऽणि प्रकृत्या स्युः इति टिलोपो न। ततो यूनि इञ्। पाणिनिः।

१२७६। ण्यक्षत्रियार्षञितो यूनि लुगणिञोः। २। ४। ५८। ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् ञितश्च परयोर्युवाभिधायिनोरणिञो र्लुक्स्यात्। कौरव्यः पिता। कौरव्यः पुत्रः। श्वाफल्कः पिता। श्वाफल्कः पुत्रः। वासिष्ठः पिता। वासिष्ठः पुत्रः। तैकायनिः पिता। तैकायनिः पुत्रः। 'एभ्यः' किम्। शिवाद्यण् कौहडः पिता। तत इञ्। कौहडिः पुत्रः। 'यूनि' किम्। वामरथ्यस्य च्छात्रा वामरथाः इत्यणो लुक्तु न भवति। आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात्। पाणिनिना प्रोक्तं पाणिनीयम्। 'वृद्धाच्छः' (सू १३३७)। 'इञश्च' (सू १३३३) इत्यण् तु न। गोत्रे य इञ्तदन्तादिति वक्ष्यमाणत्वात्। ततोऽध्येतृवेदित्रणो लुक्। स्वरे स्त्रियां च विशेषः। पाणिनीयः–पाणिनीया।

१२७७। सूत्राच्च कोपधात्। ४। २। ६५। सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक्स्यात्। अप्रोक्तार्थ आरम्भः। अष्टावध्यायाः परिमाणमस्याष्टकं पाणिनेः सूत्रम्, तदधीयते विदन्ति वा अष्टकाः।

१२७८। छन्दोब्राह्मणानि च तद्विषयाणि। ४। २। ६६। छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः। अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः। कठेन प्रोक्तमधीयते कठाः। वैशम्पायनान्तेवासित्वाण्णिनिः। तस्य 'कठचरकात्–' (सू १४८ इति लुक्। ततोऽण्। तस्य 'प्रोक्ताल्लुक्' (सू १२७४)।

१२७९। तदस्मिन्नस्तीति देशे तन्नाम्नि। ४। २। ६७। उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः।

१२८०। तेन निर्वृत्तम्। ४। २। ६८। कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी।

१२८१। तस्य निवासः। ४। २। ६९। शिबीनां निवासो देशः शैबः।

१२८२। अदूरभवश्च। ४। २। ७०। विदिशाया अदूरभवं नगरं वैदिशम्। चकारेण प्रागुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते, तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति।

१२८३। ओरञ्। ४। २। ७१। अणोऽपवादः। कक्षतु—काक्षतवम्। नद्यां तु परत्वान्मतुप्। इक्षुमती।

१२८४। मतोश्च बह्वजङ्गात्। ४। २। ७२। बह्वजङ्गं यस्य मतुपस्तदन्तादञ्। नाण्। सैध्रकावतम्। 'बह्वच्–' इति किम्। आहिमतम्। 'अङ्ग'ग्रहणं 'बह्वच्' इति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं मा भूत्।

१२८५। बह्वचः कूपेषु। ४। २। ७३। अणोऽपवादः। दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः।

१२८६। उदक्च विपाशः। ४। २। ७४। विपाश उत्तरे कूले ये कूपास्तेष्वञ्। अबह्वजर्थ आरम्भः। दन्तेन निर्वृत्तो दान्तः कूपः। 'उदक्' किम्। दक्षिणतः कूपेष्वणेव।

१२८७। संकलादिभ्यश्च। ४। २। ७५। 'कूपेषु' इति निवृत्तम्। संकलेन निर्वृत्तं सांकलम्। पौष्कलम्।

१२८८। स्त्रीषु सौवीरसाल्वप्राक्षु। ४। २। ७६। स्त्रीलिङ्गेषु देशेषु वाच्येष्वञ्: सौवीरे। दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी। साल्वे वैधूमाग्नी। प्राचि माकन्दी।

१२८९। सुवास्त्वादिभ्योऽण्। ४। २। ७७। अञोऽपवादः। सुवास्तोरदूरभवं सौवास्तवम्। वर्णु—वार्णवम्। अण्ग्रहणं नद्यां मतुपो बाधनार्थम्। सौवास्तवी।

१२९०। रोणी। ४। २। ७८। रोणीशब्दात्तदन्ताच्चाण्। कूपाञोऽपवादः। रौणः। आजकरौणः।

१२९१। कोपधाच्च। ४। २। ७९। अण्। अञोऽपवादः। कार्णच्छिद्रकः कूपः। कार्कवाकवम्। त्रैशङ्कवम्।

१२९२। वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः। ४। २। ८०। सप्तदशभ्यः सप्तदश क्रमात्स्युश्चतुरर्थ्याम्। 'अरीहणादिभ्यो वुञ्'। अरीहणेन निर्वृत्तमारीहणकम्। 'कृशाश्वादिभ्यश्छण्'। कार्शाश्वीयम्। 'ऋश्यादिभ्यः कः'। ऋश्यकम्। 'कुमुदादिभ्यष्ठच्'। कुमुदिकम्। 'काशादिभ्य इलः'। काशिलः। 'तृणादिभ्यः सः'। तृणसम्। 'प्रेक्षादिभ्य इनिः'। प्रेक्षी। 'अश्मादिभ्यो रः'। अश्मरः। 'सख्यादिभ्यो ढञ्'। साखेयम्। 'संकाशादिभ्यो ण्यः'। सांकाश्यम्। 'बलादिभ्यो यः'। बल्यम्। 'पक्षादिभ्यः फक्'। पाक्षायणः। 'पथः पन्थ च' (ग सू ७९)। पान्थायनः। 'कर्णादिभ्यः फिञ्'। कार्णायनिः। 'सुतंगमादिभ्य इञ्'। सौतंगमिः। 'प्रगद्यादिभ्यो ञ्यः'। प्रागद्यः। 'वराहादिभ्यः कक्'। वाराहकः। 'कुमुदादिभ्यष्ठक्'। कौमुदिकः।

१२९३। जनपदे लुप्। ४। २। ८१। जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात्।

१२९४। लुपि युक्तवद्व्यक्तिवचने। १। २। ५१। लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः। अङ्गाः। वङ्गाः। कलिङ्गाः।

१२९५ । तदशिष्यं संज्ञाप्रमाणत्वात् । १ । २ । ५३ । युक्तवद्वचनं न कर्तव्यं संज्ञा प्रमाणत्वात् ।

१२९६ । लुब्योगाप्रख्यानात् । १ । २ । ५४ । लुबपि न कर्तव्योऽवयवार्थस्य प्रतीतेः ।

१२९७ । योगप्रमाणे च तदभावेऽदर्शनं स्यात् । १ । २ । ५५ । यदि हि यो स्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ।

१२९८ । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । १ । २ । ५६ 'प्रत्ययार्थः प्रधानम्' इत्येवंरूपं वचनमप्यशिष्यम् । कुतः । अर्थस्य लोकत एव सिद्धेः ।

१२९९ । कालोपसर्जने च तुल्यम् । १ । २ । ५७ । 'अतीताया रात्रेः पश्चार्धेनाग मिन्याः पूर्वार्धेन च सहितो दिवसोऽद्यतनः,' 'विशेषणमुपसर्जनम्' इत्यादि पूर्वाचा परिभाषितं तत्राप्यशिष्यत्वं समानं लोकप्रसिद्धेः ।

१३०० । विशेषणानां चाजातेः । १ । २ । ५२ । लुबर्थस्य विशेषणानामपि त ल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणीयौ । 'अजातेः' किं पञ्चाला जनपदः । गोदौ ग्रामः । 'हरीतक्यादिषु व्यक्तिः' । (वा ७१५) । हरीतक फलानि हरीतक्यः । 'खलतिकादिषु वचनम्' (वा ७१६) । खलतिकस्य पर्वतस्यादू वानि खलतिकं वनानि । 'मनुष्यलुपि प्रतिषेधः' (वा ७१७) । मनुष्यलक्षणे लुबर्थे वि षणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ।

१३०१ । वरणादिभ्यश्च । ४ । २ । ८२ । अजनपदार्थ आरम्भः । वरणानामदू नगरं वरणा ।

१३०२ । शर्कराया वा । ४ । २ । ८३ । अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ।

१३०३ । ठक्छौ च । ४ । २ । ८४ । शर्कराया एतौ स्तः । कुमुदादौ वराहादौ पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्ष औत्सर्गिकोऽण् । तस्य लुब्विकल्प षड् रूपाणि । शर्करा–शार्करम्–शार्करिकम्–शर्करीयम्–शर्करिकम्–शार्करकम् ।

१३०४ । नद्यां मतुप् । ४ । २ । ८५ । चातुरर्थिकः । इक्षुमती ।

१३०५ । मध्वादिभ्यश्च । ४ । २ । ८६ । मतुप्स्याच्चातुरर्थिकः । अनद्यर्थ आरम्भ मधुमान् ।

१३०६ । कुमुदनडवेतसेभ्यो ड्मतुप् । ४ । २ । ८७ । कुमुद्वान् । नड्वान् । वेतस्वा आद्ययोः 'झयः' (सू १८९८) इत्यन्त्ये 'मादुपधायाः–' (सू १८९७) इति वक्ष्यमा वः । 'महिषाच्चेति वक्तव्यम्' (वा २७६१) । महिष्मान्नाम देशः ।

१३०७ । नडशादाड्ड्वलच् । ४ । २ । ८८ । नड्वलः । 'शादो जम्बालघासयोः' इत्यम शाद्वलः ।

१३०८ । शिखाया वलच् । ४ । २ । ८९ । शिखावलम् ।

१३०९ । उत्करादिभ्यश्छः । ४ । २ । ९० । उत्करीयः ।

१३१० । नडादीनां कुक्च । ४ । २ । ९१ । नडकीयम् । 'कुञ्चा ह्रस्वत्वं च' (ग ८०) । कुञ्चकीयः । 'तक्षन्नलोपश्च' (ग सू ८१) । तक्षकीयः ।

१३११। बिल्वकादिभ्यश्छस्य लुक्। ६। ४। १५३। नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छस्य लुक्तद्धिते परे। बिल्वा यस्यां सन्ति सा बिल्वकीया। तस्यां भवा बैल्वकाः। वेत्रकीया-वैत्रकाः। 'छस्य' किम्। छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्मा भूत्। अन्यथा 'संनियोगशिष्टानाम्' (प ८७) इति कुगपि निवर्तेत। लुग्ग्रहणं सर्वलोपार्थम्। लोपोऽपि यमात्रस्य स्यात्।

इति तद्धितचातुरर्थिकप्रकरणम्।

अथ तद्धितशैषिकप्रकरणम्।

१३१२। शेषे। ४। २। ९२। अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। औपनिषदः पुरुषः। दृषदि पिष्टा दार्षदाः सक्तवः। उलूखले क्षुण्ण औलूखलो यावकः। अश्वैरुह्यत आश्वो रथः। चतुर्भिरुह्यते चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्षः। 'शेषे' (सू १३१२) इति लक्षणं चाधिकारश्च। 'तस्य विकारः' इत्यतः प्राक्शेषाधिकारः।

१३१३। राष्ट्रावारपाराद्धखौ। ४। २। ९३। आभ्यां क्रमाद्धखौ स्तः शेषे। राष्ट्रियः। अवारपारीणः। 'अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्' (वा २७७१-२७७२)। अवारीणः। पारीणः। पारावारीणः। इह प्रकृतिविशेषाद्घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते। तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते।

१३१४। ग्रामाद्यखञौ। ४। २। ९४। ग्राम्यः-ग्रामीणः।

१३१५। कत्त्र्यादिभ्यो ढकञ्। ४। २। ९५। कुत्सितास्त्रयः कत्त्रयः। तत्र जातादिः कात्त्रेयकः। नागरेयकः। 'ग्रामात्' इत्यनुवृत्तेर्ग्रामेयकः।

१३१६। कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु। ४। २। ९६। कौलेयकः श्वा-कौलोऽन्यः। कौक्षेयकोऽसिः-कौक्षोऽन्यः। ग्रैवेयकोऽलंकारः-ग्रैवोऽन्यः।

१३१७। नद्यादिभ्यो ढक्। ४। २। ९७। नादेयम्। माहेयम्। वाराणसेयम्।

१३१८। दक्षिणापश्चात्पुरसस्त्यक्। ४। २। ९८। 'दक्षिणा' इत्याजन्तमव्ययम्। दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः।

१३१९। कापिश्याः ष्फक्। ४। २। ९९। कापिश्यां जातादि कापिशायनं मधु। कापिशायनी द्राक्षा।

१३२०। रङ्कोरमनुष्येऽण्च। ४। २। १००। चात्ष्फक्। राङ्कवो गौः राङ्कवायणः। 'अमनुष्ये' इति किम्। राङ्कवको मनुष्यः।

१३२१। द्युप्रागपागुदक्प्रतीचो यत्। ४। २। १०१। दिव्यम्। प्राच्यम्। अवाच्यम्। उदीच्यम्। प्रतीच्यम्।

१३२२। कन्थायाष्ठक्। ४। २। १०२। कान्थिकः।

१३२३। वर्णौ वुक्। ४। २। १०३। वर्णुर्नदस्तस्य समीपदेशो वर्णुस्तद्विषयार्थवाचिकन्थाशब्दाद्वुक्स्यात्। 'यथा हि जातं हिमवत्सु कान्थकम्'।

१३२४। अव्ययात्त्यप्। ४। २। १०४। 'अमेहक्वतसित्रेभ्य एव' (वा २७७९)। 'अमा-

न्तिकसहायार्थयोः'। अमात्यः। इहत्यः। क्वत्यः। ततस्त्यः। तत्रत्यः। 'परिगणनम्' कि
उपरिष्टाद्भव औपरिष्टः। 'अव्ययानां भमात्रे टिलोपः' (वा ४१८७)। अनित्योऽयं बहि
लोपविधानात्। तेनेह न। आरातीयः। शाश्वतीयः। 'त्यब्नेर्ध्रुव इति वक्तव्यम्' (वा २७८
नित्यः। 'निसो गते' (वा २७८१)।

१३२५। ह्रस्वात्तादौ तद्धिते। ८। ३। १०१। ह्रस्वादिणः परस्य सस्य षः स्या
तद्धिते। निर्गतो वर्णाश्रमेभ्यो निष्ठ्यश्चाण्डालादिः। 'अरण्याण्णः' (वा २७८२)। आर
सुमनसः। 'दूरादेत्यः' (वा २७८३)। दूरत्यः। 'उत्तरादाहञ्' (वा २७८४)। औत्तराहः।

१३२६। ऐषमोह्यःश्वसोऽन्यतरस्याम्। ४। २। १०५। एभ्यस्त्यब्वा। पक्षे व
माणौ ट्युट्युलौ। ऐषमस्त्यम्–ऐषमस्तनम्, ह्यस्त्यम्–ह्यस्तनम्। श्वस्त्यम्–श्वस्तनम्।
शौवस्तिकं वक्ष्यते।

१३२७। तीररूप्योत्तरपदादञ्ञौ। ४। २। १०६। यथासंख्येन। काकतीर
पाल्वलतीरम्। शैवरूप्यम्। 'तीररूप्यान्तात्' इति नोक्तम्। बहुच्पूर्वान्मा भूत्। बा
प्यम्।

१३२८। दिक्पूर्वपदादसंज्ञायां ञः। ४। २। १०७। अणोऽपवादः। पौर्वशालः।
ज्ञायाम्' किम्। संज्ञाभूतायाः प्रकृतेर्मा भूत्। पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः।
ग्रामनगराणाम्' (सू १४००) इत्युत्तरपदवृद्धिः।

१३२९। मद्रेभ्योऽञ्। ४। २। १०८। 'दिक्पूर्वपदात्' इत्येव। 'दिशोऽमद्राणाम्'
१३९९) इति मद्रपर्युदासादादिवृद्धिः। पौर्वमद्रः। आपरमद्रः।

१३३०। उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्। ४। २। १०९। अञ्स्यात्। शैव

१३३१। प्रस्थोत्तरपदपलद्यादिकोपधादण्। ४। २। ११०। माहिकिप्रस्
पालदः। नैलीनकः।

१३३२। कण्वादिभ्यो गोत्रे। ४। २। १११। एभ्यो गोत्रप्रत्ययान्तेभ्योऽण्
कण्वो गर्गादिः। काण्वस्य छात्राः काण्वाः।

१३३३। इञश्च। ४। २। ११२। गोत्रे य इञ् तदन्तादण्स्यात्। दाक्षाः।
किम्। सौतंगमेरिदं सौतङ्गमीयम्। गोत्रमिह शास्त्रीयम्। न तु लौकिकम्। तेन
पाणिनीयम्।

१३३४। न द्व्यचः प्राच्यभरतेषु। ४। २। ११३। 'इञश्च' (सू १३३३)
ऽपवादः। प्राष्ठीयाः। काशीयाः। भरतानां प्राच्यत्वेऽपि पृथगुपादानम्। अन्यत्र
हणे भरतानामग्रहणस्य लिङ्गम्।

१३३५। वृद्धिर्यस्याचामादिस्तद्वृद्धम्। १। १। ७३। यस्य समुदायस्याचां
आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्।

१३३६। त्यदादीनि च। १। १। ७४। वृद्धसंज्ञानि स्युः।

१३३७। वृद्धाच्छः। ४। २। ११४। शालीयः। मालीयः। तदीयः।

१३३८। एङ् प्राचां देशे। १। १। ७५। एङ् यस्याचामादिस्तद्वृद्धसंज्ञं वा स
भिधाने। एणीपचनीयः। गोनर्दीयः। भोजकटीयः। पक्षेऽणि। ऐणीपचनः। गौनर्दः।

कटः । 'एङ्' किम् । आहिच्छत्रः । कान्यकुब्जः । 'वा नामधेयस्य वृद्धसंज्ञा वक्तव्या' (वा ९७६) । देवदत्तः—देवदत्तीयः ।

१३३९ । भवतष्ठक्छसौ । ४ । २ । ११५ । वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । 'वृद्धात्' इत्यनुवृत्तेः शत्रन्तादणेव । भावतः ।

१३४० । काश्यादिभ्यष्ठञ्ञिठौ । ४ । २ । ११६ । इकार उच्चारणार्थः । काशिकी—काशिका । वैदिकी—वैदिका । 'आपदादिपूर्वपदात्कालान्तात्' (ग सू ७४) । आपदादिराकृतिगणः । आपत्कालिकी—आपत्कालिका ।

१३४१ । वाहीकग्रामेभ्यश्च । ४ । २ । ११७ । वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी—कास्तीरिका ।

१३४२ । विभाषोशीनरेषु । ४ । २ । ११८ । एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ वा स्तः । सौदर्शनिकी—सौदर्शनिका—सौदर्शनीया ।

१३४३ । ओर्देशे ठञ् । ४ । २ । ११९ । उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षुः । नैषादकर्षुकः । 'केऽणः' (सू ८३४) इति ह्रस्वः । 'देशे' किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ्ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकर्षुकः ।

१३४४ । वृद्धात्प्राचाम् । ४ । २ । १२० । प्राग्देशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह । मल्लवास्तु—माल्लवास्तवः ।

१३४५ । धन्वयोपधाद्वुञ् । ४ । २ । १२१ । धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । सांकाश्यकाम्पिल्यशब्दौ 'वुञ्छण्—' (सू १२९२) आदिसूत्रेण ण्यान्तौ । सांकाश्यकः । काम्पिल्यकः ।

१३४६ । प्रस्थपुरवहान्ताच्च । ४ । २ । १२२ । एतदन्ताद्वृद्धाद्देशवाचिनो वुञ्स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राग्देशे तूत्तरेण सिद्धम् ।

१३४७ । रोपधेतोः प्राचाम् । ४ । २ । १२३ । रोपधादीकारान्ताच्च प्राग्देशवाचिनश्च वृद्धाद्वुञ्स्यात् । पाटलिपुत्रकः । ईतः । काकन्दकः ।

१३४८ । जनपदतदवध्योश्च । ४ । २ । १२४ । जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ्स्यात् । आदर्शकः । त्रैगर्तकः ।

१३४९ । अवृद्धादपि बहुवचनविषयात् । ४ । २ । १२५ । अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ्स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः; आजमीढकः । वृद्धाज्जनपदाद्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । 'विषयग्रहणम्' किम् । एकशेषेण बहुत्वे मा भूत् । वर्तनी वर्तनी च वर्तनी च वर्तन्यः । तासु भवो वार्तनः ।

१३५० । कच्छाग्निवक्त्रवर्तोत्तरपदात् । ४ । २ । १२६ । देशवाचिनो वृद्धादवृद्धाच्च वुञ्स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः ।

१३५१ । धूमादिभ्यश्च । ४ । २ । १२७ । देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः ।

१३५२। नगरात्कुत्सनप्रावीण्ययोः ।४।२।१२८। नगरशब्दाद्वुञ्स्यात्
प्रावीण्ये च गम्ये। नागरकश्चौरः शिल्पी वा। 'कुत्सन–' इति किम्। नागरा ब्राह्मणाः।

१३५३। अरण्यान्मनुष्ये।४।२।१२९। वुञ्। 'अरण्याण्णः' (वा २७८८)।
स्यापवादः। 'पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम्' (वा २८१९)। आ
पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा। 'वा गोमयेषु' (वा २८२०)। आरण्य
आरण्या वा गोमयाः।

१३५४। विभाषा कुरुयुगंधराभ्याम् ।४।२।१३०। वुञ्। कौरवकः–कौ
यौगंधरकः–यौगंधरः।

१३५५। मद्रवृज्योः कन् ।४। २।१३१। जनपदवुञोऽपवादः। मद्रेषु
मद्रकः। वृजिकः।

१३५६। कोपधादण्।४।२।१३२। माहिषिकः।

१३५७। कच्छादिभ्यश्च ।४ ।२ ।१३३ । देशवाचिभ्योऽण्। वुञादेरपवा
काच्छः। सैन्धवः।

१३५८। मनुष्यतत्स्थयोर्वुञ्।४।२।१३४। कच्छाद्यणोऽपवादः। कच्छे
काच्छको मनुष्यः। काच्छकं हसितम्। 'मनुष्य–' इति किम्। काच्छो गौः।

१३५९। अपदातौ साल्वात्।४।२।१३५। साल्वशब्दस्य कच्छादित्वाद्वुञि
नियमार्थमिदम्। अपदातावेवेति। साल्वको ब्राह्मणः। 'अपदातौ' किम्। साल्व
तिर्व्रजति।

१३६०। गोयवाग्वोश्च।४।२।१३६। साल्वाद्वुञ्। कच्छाद्यणोऽपवादः।
गौः–साल्विका यवागूः–साल्वमन्यत्।

१३६१। गर्तोत्तरपदाच्छः।४।२।१३७। देशे। अणोऽपवादः। वृकगर्त
उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम्।

१३६२। गहादिभ्यश्च।४।२।१३८। छः स्यात्। गहीयः। 'मुखपार्श्वतसे
(ग सू ७८)। मुखतीयम्। पार्श्वतीयम्। अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञाप
दम्। 'कुग्जनस्य परस्य च' (ग सू ८९)। जनकीयम्। परकीयम्। 'देवस्य च' (ग
देवकीयम्। स्वकीयम्। 'वेणुकादिभ्यश्छण्वाच्यः' (ग सू ९१)। वेणुकीयम्। वैत्र
औत्तरपदकीयम्।

१३६३। प्राचां कटादेः।४।२।१३९। प्राग्देशवाचिनः कटादेश्छः स्यात्।
ऽपवादः। कटनगरीयम्। कटघोषीयम्। कटपल्वलीयम्।

१३६४। राज्ञः क च।४।२।१४०। वृद्धत्वाच्छे सिद्धे तत्संनियोगेन क
विधीयते। राजकीयम्।

१३६५। वृद्धादकेकान्तखोपधात्।४।२।१४१। 'अक' 'इक' एतद
धाच्च वृद्धाद्देशवाचिनश्छः स्यात्। ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजी
जातो ब्राह्मणकीयः। शाल्मलिकीयः। अयोमुखीयः।

---

१ स्वार्थिककन्नन्तात्स्वशब्दाद्गहादेराकृतिगणत्वाच्छः—इति मनोरमातत्त्वबोधि

१३६६ । कन्थापलदनगरग्रामह्रदोत्तरपदात् । ४ । २ । १४२ । कन्थादिपञ्चकोत्तरपदा-द्देशवाचिनो वृद्धाच्छः स्यात् । ठञ्ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षि-नगरीयम् । दाक्षिग्रामीयम् । दाक्षिह्रदीयम् ।

१३६७ । पर्वताच्च । ४ । २ । १४३ । पर्वतीयः ।

१३६८ । विभाषामनुष्ये । ४ । २ । १४४ । मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण् । पर्वतीयानि–पार्वतानि वा फलानि । 'अमनुष्ये' किम् । पर्वतीयो मनुष्यः ।

१३६९ । कृकणपर्णाद्भारद्वाजे । ४ । २ । १४५ । भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । 'भारद्वाजे' किम् । कार्कणम् । पार्णम् ।

१३७० । युष्मदस्मदोरन्यतरस्यां खञ्च । ४ । ३ । १ । चाच्छः । पक्षेऽण् । युवयोः युष्माकं वा अयं युष्मदीयः । अस्मदीयः ।

१३७१ । तस्मिन्नणि च युष्माकास्माकौ । ४ । ३ । २ । युष्मदस्मदोरेतावादेशौ स्त-स्खञ्यणि च । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः ।

१३७२ । तवकममकावेकवचने । ४ । ३ । ३ । एकार्थवाचिनोर्युष्मदस्मदोस्तवकम-मकौ स्तः खञ्यणि च । तावकीनः–तावकः । मामकीनः–मामकः । छे तु ।

१३७३ । प्रत्ययोत्तरपदयोश्च । ७ । २ । ९८ । मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः । उत्तरपदे तु त्वत्पुत्रः । मत्पुत्रः ।

१३७४ । अर्धाद्यत् । ४ । ३ । ४ । अर्ध्यः ।

१३७५ । परावराधमोत्तमपूर्वाच्च । ४ । ३ । ५ । परार्ध्यम् । अवरार्ध्यम् । अधमा-र्ध्यम् । उत्तमार्ध्यम् ।

१३७६ । दिक्पूर्वपदाट्ठञ्च । ४ । ३ । ६ । चाद्यत् । पौर्वार्धिकम्–पूर्वार्ध्यम् ।

१३७७ । ग्रामजनपदैकदेशादञ्ठञौ । ४ । ३ । ७ । ग्रामैकदेशवाचिनो जनपदैकदे-शवाचिनश्च दिक्पूर्वपदादर्धान्तादञ्ठञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः–पौर्वार्धिकाः । ग्रामस्य पूर्वस्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठञ्ग्रहणं स्पष्टार्थम् । चेत्युक्तेर्यतोऽप्यनुकर्षः संभाव्येत ।

१३७८ । मध्यान्मः । ४ । ३ । ८ । मध्यमः ।

१३७९ । अ सांप्रतिके । ४ । ३ । ९ । मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वम् । नातिदीर्घमित्यर्थः ।

१३८० । द्वीपादनुसमुद्रं यञ् । ४ । ३ । १० । समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्द्वीप-शब्दाद्यञ्स्यात् । द्वैप्यम्–द्वैप्या ।

१३८१ । कालाट्ठञ् । ४ । ३ । ११ । कालवाचिभ्यष्ठञ्स्यात् । मासिकम् । सांवत्सरि-कम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि 'शार्वरस्य तमसो निषिद्धये' इति कालिदासः । 'अनुदितौषसरागा' इति भारविः । समानकालीनम् । प्राक्कालीनमित्यादि च । 'अपभ्रंशा एवैते' इति प्रामाणिकाः । 'तत्र जातः' (सू १२९२) इति यावत्कालाधिकारः ।

१३८२ । श्राद्धे शरदः । ४ । ३ । १२ । ठञ्स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ।

१३८३ । विभाषा रोगातपयोः । ४ । ३ । १३ । शारदिकः—शारदो वा रोग आतपो॰ 'एतयोः' किम् । शारदं दधि ।

१३८४ । निशाप्रदोषाभ्यां च । ४ । ३ । १४ । वा ठञ्स्यात् । नैशिकम्—नै॰ प्रादोषिकम्—प्रादोषम् ।

१३८५ । श्वसस्तुट् च । ४ । ३ । १५ । श्वस्शब्दाट्ठञ्वा स्यात् । तस्य तुडाग॰

१३८६ । द्वारादीनां च । ७ । ३ । ४ । द्वार । स्वर । स्वाध्याय । व्यल्कश । स्व॰ स्वर् । स्फ्यकृत् । स्वादुमृदु । श्वस् । श्वन् । स्व । एषां न वृद्धिरैजागमश्च । शौवस्तिकम्

१३८७ । संधिवेलाद्यृतुनक्षत्रेभ्योऽण् । ४ । ३ । १६ । संधिवेलादिभ्य ऋतुभ्यो॰ त्रेभ्यश्च कालवृत्तिभ्योऽण्स्यात् । संधिवेलायां भवं सांधिवेलम् । ग्रैष्मम् । तैषम् । संधि॰ संध्या । अमावस्या । त्रयोदशी । चतुर्दशी । पौर्णमासी । प्रतिपत् । 'संवत्सरात्फलप॰ (ग सू ९२) । सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ।

१३८८ । प्रावृष एण्यः । ४ । ३ । १७ । प्रावृषेण्यः ।

१३८९ । वर्षाभ्यष्ठक् । ४ । ३ । १८ । वर्षासु साधु वार्षिकं वासः । 'कालात्साधु॰ त्पच्यमानेषु' (सू १४१८) इति साध्वर्थे ।

१३९० । सर्वत्राण्च तलोपश्च । ४ । ३ । २२ । हेमन्तादण्स्यात्तलोपश्च वेदलोक॰ चकारात्पक्षे ऋत्वण् । हैमनम्—हैमन्तम् ।

१३९१ । सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च । ४ । ३ । २३ । सा॰ त्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागन्ता॰ 'अनद्यतने—' (सू २१८५) इत्यादिनिर्देशात् । सायंतनम् । चिरंतनम् । प्राह्णप्रगयोरे॰ निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् । 'चिरपरुत्परारिभ्यस्त्नो व॰ (वा २८४३) । चिरत्नम् । परुत्नम् । परारित्नम् । 'अग्रादिपश्चाड्डिमच्' (वा २८॰ अग्रिमम् । आदिमम् । पश्चिमम् । 'अन्ताच्च' (वा २८४५) । अन्तिमम् ।

१३९२ । विभाषा पूर्वाह्णापराह्णाभ्याम् । ४ । ३ । २४ । आभ्यां ट्युट्यु॰ स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । 'घकालतनेषु—' (सू॰ इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वा॰ आपराह्णिकम् ।

१३९३ । तत्र जातः । ४ । ३ । २५ । सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो॰ स्युः । स्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ।

१३९४ । प्रावृषष्ठप् । ४ । ३ । २६ । एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ।

१३९५ । संज्ञायां शरदो वुञ् । ४ । ३ । २७ । ऋत्वणोऽपवादः । शारदका॰ दर्भविशेषा मुद्गविशेषाश्च ।

१३९६ । उत्तरपदस्य । ७ । ३ । १० । अधिकारोऽयम् । 'हनस्तः—' (सू॰ इत्यस्मात्प्राक् ।

१३९७ । अवयवादृतोः । ७ । ३ । ११ । अवयववाचिनः पूर्वपदादृतुवाचिनो॰ रचो वृद्धिः स्यात् । ञिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । 'अ॰

किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः । 'ऋतोर्वृद्धिमद्विधाववयवानाम्' (वा ९६०) इति तदन्तविधिः पूर्वत्र । इह तु नावयवत्वाभावात् ।

१३९८ । सुसर्वार्धाज्जनपदस्य । ७ । ३ । १२ । उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । अर्धपाञ्चालकः । 'जनपदतदवध्योः–' (सू १३४८) इति वुञ् । 'सुसर्वार्धदिक्छब्देभ्यो जनपदस्य' (वा ५५९) इति तदन्तविधिः ।

१३९९ । दिशोऽमद्राणाम् । ७ । ३ । १३ । दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । 'दिशः' किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । 'अमद्राणाम्' किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ।

१४०० । प्राचां ग्रामनगराणाम् । ७ । ३ । १४ । दिशः परेषां ग्रामवाचिनां नगरवाचिनां चाङ्गानामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । नगरे पूर्वपाटलिपुत्रकः ।

१४०१ । पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् । ४ । ३ । २८ । पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ।

१४०२ । पथः पन्थ च । ४ । ३ । २९ । पथि जातः पन्थकः ।

१४०३ । अमावास्याया वा । ४ । ३ । ३० । अमावास्यकः–आमावास्यः ।

१४०४ । अ च । ४ । ३ । ३१ । अमावास्यः ।

१४०५ । सिन्ध्वपकराभ्यां कन् । ४ । ३ । ३२ । सिन्धुकः । कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ।

१४०६ । अणञौ च । ४ । ३ । ३३ । क्रमात्स्तः । सैन्धवः । आपकरः ।

१४०७ । श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ४ । ३ । ३४ । एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक्स्यात् ।

१४०८ । लुक्तद्धितलुकि । १ । २ । ४९ । तद्धितलुकि सत्युपसर्जनस्त्रीप्रत्ययस्य लुक्स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि । 'चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्' (वा २८५७) । चित्रायां जाता चित्रा । रेवती रोहिणी आभ्यां 'लुक्तद्धितलुकि' (सू १४०८) इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् । 'फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ' (वा २८५८) । स्त्रियामित्येव । फल्गुनी । अषाढा । 'श्रविष्ठाषाढाभ्यां छण्वक्तव्यः' (वा २८५९) । अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ।

१४०९ । जे प्रोष्ठपदानाम् । ७ । ३ । १८ । प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । 'जे' इति किम् । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भद्रपादः ।

१४१० । स्थानान्तगोशालखरशालाच्च । ४ । ३ । ३५ । एभ्यो जातार्थप्रत्ययस्य लुक्स्यात् । गोस्थाने जातो गोस्थानः । गोशालः । खरशालः । 'विभाषा सेना–' (सू ८२८) इति नपुंसकत्वे ह्रस्वत्वम् ।

१४११ । वत्सशालाभिजिदश्वयुक्छतभिषजो वा । ४ । ३ । ३६ । एभ्यो जातार्थस्य

लुग्वा स्यात्। वत्सशाले जातो वत्सशालः–वात्सशाल इत्यादि । 'जातार्थे प्रतिप्रसूतोऽ... डिद्वक्तव्यः' (वा २६९०) । शातभिषजः–शातभिषः–शतभिषक्।

१४१२ । नक्षत्रेभ्यो बहुलम् । ४ । ३ । ३७ । जातार्थप्रत्ययस्य बहुलं लुक्स्यात्... रोहिणः–रौहिणः।

१४१३ । कृतलब्धक्रीतकुशलाः । ४ । ३ । ३८ । 'तत्र' इत्येव । स्रुघ्ने कृतो ल... क्रीतः कुशलो वा स्रौघ्नः।

१४१४ । प्रायभवः । ४ । ३ । ३९ । 'तत्र' इत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः...

१४१५ । उपजानूपकर्णोपनीवेष्ठक् । ४ । ३ । ४० । औपजानुकः । औपकर्णिकः... औपनीविकः।

१४१६ । संभूते । ४ । ३ । ४१ । स्रुघ्ने संभवति स्रौघ्नः।

१४१७ । कोशाड्ढञ् । ४ । ३। ४२ । कौशेयं वस्त्रम्।

१४१८ । कालात्साधुपुष्प्यत्पच्यमानेषु । ४ । ३ । ४३ । हेमन्ते साधुर्हैमन्... प्राकारः। वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। शरदि पच्यन्ते शारदाः शालयः।

१४१९ । उप्ते च । ४ । ३ । ४४ । हेमन्त उप्यन्ते हैमन्ता यवाः।

१४२० । आश्वयुज्या वुञ् । ४ । ३ । ४५ । ठञोऽपवादः । आश्वयुज्यामुप्ता आश्व... जका माषाः।

१४२१ । ग्रीष्मवसन्तादन्यतरस्याम् । ४ । ३ । ४६ । पक्षे ऋत्वण् । ग्रैष्मकः... ग्रैष्मम्। वासन्तकम्–वासन्तम्।

१४२२ । देयमृणे । ४ । ३ । ४७ । 'कालात्' इत्येव । मासे देयमृणं मासिकम्।

१४२३ । कलाप्यश्वत्थयवबुसाद्वुन् । ४ । ३ । ४८ । यस्मिन्काले मयूराः कलापि... भवन्ति स उपचारात्कलापी तत्र देयमृणं कलापकम् । अश्वत्थस्य फलमश्वत्थः । तद्यु... कालोऽप्यश्वत्थः। यस्मिन्कालेऽश्वत्थाः फलन्ति तत्र देयमृणमश्वत्थकम् । यस्मिन्यवबुसः... त्पद्यते तत्र देयमृणं यवबुसकम्।

१४२४ । ग्रीष्मावरसमाद्वुञ् । ४ । ३ । ४९ । ग्रीष्मे देयमृणं ग्रैष्मकम् । आवरसमकः...

१४२५ । संवत्सराग्रहायणीभ्यां ठञ्च । ४ । ३ । ५० । चाद्वुञ् । सांवत्सरिकः... सांवत्सरकम्। आग्रहायणिकम्–आग्रहायणकम्।

१४२६ । व्याहरति मृगः । ४ । ३ । ५१ । कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थेऽ... दयः स्युः। यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः–नैशिकः।

१४२७ । तदस्य सोढम् । ४ । ३ । ५२ । 'कालात्' इत्येव । निशा सहचरितमध्य... निशा तत्सोढमस्य नैशिकः–नैशः।

१४२८ । तत्र भवः । ४ । ३ । ५३ । स्रुघ्ने भवः स्रौघ्नः । राष्ट्रियः।

१४२९ । दिगादिभ्यो यत् । ४ । ३ । ५४ । दिश्यम् । वर्ग्यम्।

१४३० । शरीरावयवाच्च । ४ । ३ । ५५ । दन्त्यम् । कण्ठ्यम्।

१४३१ । प्राचां नगरान्ते । ७ । ३ । २४ । प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्...

दस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च। सुह्मनगरे भवः सौह्मनागरः। पौर्वनागरः। 'प्राचाम्' किम्। मद्रनगरमुदक्षु तत्र भवो माद्रनगरः।

१४३२। जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्। ७। ३। २५। जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च। कुरुजङ्गले भवं कौरुजङ्गलम्–कौरुजाङ्गलम्। वैश्वधेनवम्–वैश्वधैनवम्। सौवर्णवलजम्–सौवर्णवालजम्।

१४३३। दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्। ४। ३। ५६। दार्तेयम्। कौक्षेयम्। कलशिर्घटस्तत्र भवं कालशेयम्।

१४३४। ग्रीवाभ्योऽण्च। ४। ३। ५७। चाड्ढञ्। ग्रैवेयम्–ग्रैवम्।

१४३५। गम्भीराञ्ञ्यः। ४। ३। ५८। गम्भीरे भवं गाम्भीर्यम्। 'पञ्चजनादुपसंख्यानम्' (वा २८६८)। पाञ्चजन्यः।

१४३६। अव्ययीभावाच्च। ४। ३। ५९। परिमुखं भवं पारिमुख्यम्। 'परिमुखादिभ्य एवेष्यते' (वा २८६६)। नेह। औपकूलः।

१४३७। अन्तःपूर्वपदाट्ठञ्। ४। ३। ६०। 'अव्ययीभावात्' इत्येव। वेश्मन्यन्तोऽन्तर्वेश्मम्। तत्र भवमान्तर्वेश्मिकम्। आन्तर्गणिकम्। 'अध्यात्मादेष्ठञिष्यते' (वा २८६९)। अध्यात्मं भवमाध्यात्मिकम्।

१४३८। अनुशतिकादीनां च। ७। ३। २०। एषामुभयपदवृद्धिः स्यात्। ञिति णिति किति च। आधिदैविकम्। आधिभौतिकम्। ऐहलौकिकम्। पारलौकिकम्। अध्यात्मादिराकृतिगणः।

१४३९। देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्। ७। ३। १। एषां पञ्चानां वृद्धिप्राप्तावादेरच आत् ञिति णिति किति च। दाविकम्। देविकाकूले भवा दाविकाकूलाः शालयः। शिंशपाया विकारः शांशपश्चमसः। 'पलाशादिभ्यो वा' (सू १५२१) इत्यञ्। दित्यौह इदं दात्यौहम्। दीर्घसत्रे भवं दार्घसत्रम्। श्रेयसि भवं श्रायसम्।

१४४०। ग्रामात्पर्यनुपूर्वात्। ४। ३। ६१। ठञ् स्यात्। 'अव्ययीभावात्' इत्येव। पारिग्रामिकः। आनुग्रामिकः।

१४४१। जिह्वामूलाङ्गुलेश्छः। ४। ३। ६२। जिह्वामूलीयम्। अङ्गुलीयम्।

१४४२। वर्गान्ताच्च। ४। ३। ६३। कवर्गीयम्।

१४४३। अशब्दे यत्खावन्यतरस्याम्। ४। ३। ६४। पक्षे पूर्वेण च्छः। मद्रवर्ग्यः–मद्रवर्गीणः–मद्रवर्गीयः। 'अशब्दे' किम्। कवर्गीयो वर्णः।

१४४४। कर्णललाटात्कनलंकारे। ४। ३। ६५। कर्णिका। ललाटिका।

१४४५। तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः। ४। ३। ६६। सुपां व्याख्यानः सौपो ग्रन्थः। तैङः। कार्तः। सुप्सु भवं सौपम्।

१४४६। बह्वचोऽन्तोदात्ताट्ठञ्। ४। ३। ६७। षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम्। तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः।

१४४७। क्रतुयज्ञेभ्यश्च। ४। ३। ६८। सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते। अग्निष्टोमस्य व्याख्यान-

स्तत्र भव आग्निष्टोमिकः। वाजपेयिकः। पाकयज्ञिकः। नावयज्ञिकः। बहुवचनं स्वरूपवि-
धिनिरासार्थम्। अनन्तोदात्तार्थ आरम्भः।

१४४८। अध्यायेष्वेवर्षेः। ४। ३। ६९। ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्ति-
भ्यो भवे व्याख्याने चाध्याये ठञ्स्यात्। वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्त-
भवो वा वासिष्ठिकोऽध्यायः। 'अध्यायेषु' किम्। वासिष्ठी ऋक्।

१४४९। पौरोडाशपुरोडाशात्ष्ठन्। ४। ३। ७०। पुरोडाशसहचरितो मन्त्रः पुरो-
डाशः। स एव पौरोडाशः। ततः ष्ठन्। पौरोडाशिकः। पुरोडाशिकः।

१४५०। छन्दसो यदणौ। ४। ३। ७१। छन्दस्यः-छान्दसः।

१४५१। द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक्। ४। ३। ७२
द्व्यचः। ऐष्टिकः। पाशुकः। ऋतः। चातुर्होतृकः। ब्राह्मणिकः। आर्चिक इत्यादि।

१४५२। अणृगयनादिभ्यः। ४। ३। ७३। ठञादेरपवादः। आर्गयनः। औपनि-
दः। वैयाकरणः।

१४५३। तत आगतः। ४। ३। ७४। स्रुघ्नादागतः स्रौघ्नः।

१४५४। ठगायस्थानेभ्यः। ४। ३। ७५। शुल्कशालाया आगतः शौल्कशालिकः

१४५५। शुण्डिकादिभ्योऽण्। ४। ३। ७६। आयस्थानठकश्छादीनां चापवादः
शुण्डिकादागतः शौण्डिकः। कार्कणः। तैर्थः।

१४५६। विद्यायोनिसंबन्धेभ्यो वुञ्। ४। ३। ७७। औपाध्यायकः। पैतामहकः

१४५७। ऋतष्ठञ्। ४। ३। ७८। वुञोऽपवादः। हौतृकम्। भ्रातृकम्।

१४५८। पितुर्यच्च। ४। ३। ७९। चाट्ठञ्। 'रीङृतः' (सू १२३४)। 'यस्य-'(सू ३।
इति लोपः। पित्र्यम्-पैतृकम्।

१४५९। गोत्रादङ्कवत्। ४। ३। ८०। बिदेभ्य आगतं बैदम्। गार्गम्। दाक्ष-
औपगवकम्।

१४६०। नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्। ७। ३। ३०। नञः परेषां शुच्या-
दिपञ्चानामादेरचो वृद्धिः पूर्वपदस्य त वा ञिदादौ परे। आशौचम्-अशौचम्। आनैश्वर्यम्-
अनैश्वर्यम्। आक्षैत्रज्ञम्-अक्षैत्रज्ञम्। आकौशलम्-अकौशलम्। आनैपुणम्-अनैपुणम्

१४६१। हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः। ४। ३। ८१। समादागतं समरूप्यम्
विषमरूप्यम्। पक्षे गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्-देवदत्तम्
देवदत्तीयम्।

१४६२। मयट् च। ४। ३। ८२। सममयम्। विषममयम्। देवदत्तमयम्।

१४६३। प्रभवति। ४। ३। ८३। 'ततः' इत्येव। हिमवतः प्रभवति हैमवती गङ्गा

१४६४। विदूराञ्ञ्यः। ४। ३। ८४। विदूरात्प्रभवति वैदूर्यो मणिः।

१४६५। तद्गच्छति पथिदूतयोः। ४। ३। ८५। स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो

१४६६। अभिनिष्क्रामति द्वारम्। ४। ३। ८६। 'तत्' इत्येव। स्रुघ्नमभिनिष्क्रामति
स्रौघ्नं कान्यकुब्जद्वारम्।

१४६७। अधिकृत्य कृते ग्रन्थे। ४। ३। ८७। 'तत्' इत्येव। शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः। शारीरकं भाष्यमिति त्वभेदोपचारात्।

१४६८। शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः। ४। ३। ८८। शिशूनां क्रन्दनं शिशुक्रन्दः। तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमस्य सभा यमसभम्। क्लीवत्वं निपातनात्। यमसभीयः। किरातार्जुनीयम्। इन्द्रजननादिराकृतिगणः। इन्द्रजननीयम्। विरुद्धभोजनीयम्।

१४६९। सोऽस्य निवासः। ४। ३। ८९। स्रुघ्नो निवासोऽस्य स्रौघ्नः।

१४७०। अभिजनश्च। ४। ३। ९०। स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः। 'यत्र स्वयं वसति स निवासः'। 'यत्र पूर्वैरुषितं सोऽभिजनः' इति विवेकः।

१४७१। आयुधजीविभ्यश्छः पर्वते। ४। ३। ९१। पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात्। हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्गोलीयाः। 'आयुध-' इति किम्। ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः।

१४७२। शण्डिकादिभ्यो ञ्यः। ४। ३। ९२। शण्डिकोऽभिजनोऽस्य शाण्डिक्यः।

१४७३। सिन्धुतक्षशिलादिभ्योऽणञौ। ४। ३। ९३। सिन्ध्वादिभ्योऽण्तक्षशिलादिभ्योऽञ्स्यादुक्तेऽर्थे। सैन्धवः। तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः।

१४७४। तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः। ४। ३। ९४। तूदी अभिजनोऽस्य तौदेयः। शालातुरीयः। वार्मतेयः। कौचवार्यः।

१४७५। भक्तिः। ४। ३। ९५। 'सोऽस्य' इत्यनुवर्तते। भज्यते सेव्यत इति भक्तिः। स्रुघ्नो भक्तिरस्य स्रौघ्नः।

१४७६। अचित्तादेशकालाट्ठक्। ४। ३। ९६। अपूपा भक्तिरस्य आपूपिकः। पायसिकः। 'अचित्तात्' किम्। दैवदत्तः। 'अदेशात्' किम्। स्रौघ्नः। 'अकालात्' किम्। ग्रैष्मः।

१४७७। महाराजाट्ठञ्। ४। ३। ९७। माहाराजिकः।

१४७८। वासुदेवार्जुनाभ्यां वुन्। ४। ३। ९८। वासुदेवकः। अर्जुनकः।

१४७९। गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्। ४। ३। ९९। अणोऽपवादः। परत्वाद्वृद्धाच्छं बाधते। ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः। नाकुलकः। बहुलग्रहणान्नेह। पाणिनो भक्तिरस्य पाणिनीयः।

१४८०। जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने। ४। ३। १००। जनपदस्वामिवाचिनां बहुवचने जनपदवाचिना समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च। 'जनपदतदवध्योश्च' (सू १३४८) इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते। अङ्गा जनपदो भक्तिरस्याङ्गकः। अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः। 'जनपदिनाम्' किम्। पञ्चाला ब्राह्मणा भक्तिरस्य पाञ्चालाः। 'जनपदेन' इति किम्। पौरवो राजा भक्तिरस्य पौरवीयः।

१४८१। तेन प्रोक्तम्। ४। ३। १०१। पाणिनिना प्रोक्तं पाणिनीयम्।

१४८२ । तित्तिरिवरतन्तुखण्डिकोखाच्छण् । ४ । ३ । १०२ । 'छन्दोब्राह्मणानि-' (सू १२७८) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ।

१४८३ । काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । ४ । ३ । १०३ । काश्यपेन प्रोक्त-मधीयते काश्यपिनः ।

१४८४ । कलापिवैशम्पायनान्तेवासिभ्यश्च । ४ । ३ । १०४ । कलाप्यन्तेवासिभ्यः- हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवासिभ्य आलम्बिनः ।

१४८५ । पुराणप्रोक्तेषु ब्राह्मणकल्पेषु । ४ । ३ । १०५ । तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् । यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरंतनेन मुनिना प्रोक्ताः भल्लु--भाल्लविनः । शाट्यायनः--शाट्यायनिनः । कल्पे । पिङ्गेन प्रोक्तः पैङ्गी कल्पः । 'पुराण-' इति किम् । याज्ञवल्क्यानि ब्राह्मणानि । आश्मरथः कल्पः । अणि । 'आपत्यस्य-' (सू १०८२) इति यलोपः ।

१४८६ । शौनकादिभ्यश्छन्दसि । ४ । ३ । १०६ । छन्दस्यभिधेय एभ्यो णिनिः शौनकेन प्रोक्तमधीयते शौनकिनः ।

१४८७ । कठचरकाल्लुक् । ४ । ३ । १०७ । आभ्यां प्रोक्तप्रत्ययस्य लुक्स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ।

१४८८ । कलापिनोऽण् । ४ । ३ । १०८ । कलापिना प्रोक्तमधीयते कलापाः । 'नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम्' (वा ४१८३) इत्युपसंख्यानाट्टिलोपः ।

१४८९ । छगलिनो ढिनुक् । ४ । ३ । १०९ । छागलिना प्रोक्तमधीयते छागलेयिनः ।

१४९० । पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । ४ । ३ । ११० । पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ।

१४९१ । कर्मन्दकृशाश्वादिनिः । ४ । ३ । १११ । 'भिक्षुनटसूत्रयोः' इत्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ।

१४९२ । तेनैकदिक् । ४ । ३ । ११२ । सुदाम्ना अद्रिणा एकदिक्सौदामनी ।

१४९३ । तसिश्च । ४ । ३ । ११३ । स्वरादिपाठादव्ययत्वम् । पीलुमूलेन एकदिक्पी-लुमूलतः ।

१४९४ । उरसो यच्च । ४ । ३ । ११४ । चात्तसिः । अणोऽपवादः । उरसैकदिगुरस्यः । उरस्तः ।

१४९५ । उपज्ञाते । ४ । ३ । ११५ । 'तेन' इत्येव । पाणिनिनोपज्ञातं पाणिनीयम् ।

१४९६ । कृते ग्रन्थे । ४ । ३ । ११६ । वररुचिना कृतो वाररुचो ग्रन्थः ।

१४९७ । संज्ञायाम् । ४ । ३ । ११७ । 'तेन' इत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ।

१४९८ । कुलालादिभ्यो वुञ् । ४ । ३ । ११८ । तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ।

१४९९ । क्षुद्राभ्रमरवटरपादपादञ् । ४ । ३ । ११९ । तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ।

१५०० । तस्येदम् । ४ । ३ । १२० । उपगोरिदमौपगवम् । 'वहेस्तुरणिट् च' (वा २९१०)। संवोढुः स्वं सांवहित्रम् । 'अग्नीधः शरणे रणभं च' (वा २९११)। अग्निमिन्धे अग्नीत् । तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः । 'समिधामाधाने षेण्यण्' (वा २९१२) । सामिधेन्यो मन्त्रः—सामिधेनी ऋक् ।

१५०१ । रथाद्यत् । ४ । ३ । १२१ । रथ्यं चक्रम् ।

१५०२ । पत्त्रपूर्वादञ् । ४ । ३ । १२२ । पात्त्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ।

१५०३ । पत्त्राध्वर्युपरिषदश्च । ४ । ३ । १२३ । अञ् । 'पत्त्राद्वाह्ये' (वा २९०८)। अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् । पारिषदम् ।

१५०४ । हलसीराट्ठक् । ४ । ३ । १२४ । हालिकम् । सैरिकम् ।

१५०५ । द्वन्द्वाद्वुन्वैरमैथुनिकयोः । ४ । ३ । १२५ । काकोलूकिका । कुत्सकुशिकिका । 'वैरे देवासुरादिभ्यः प्रतिषेधः' (वा २९१४) । दैवासुरम् ।

१५०६ । गोत्रचरणाद्वुञ् । ४ । ३ । १२६ । औपगवकम् । 'चरणाद्धर्माम्नाययोरिति' वक्तव्यम्' (वा २९१३) । काठकम् ।

१५०७ । संघाङ्कलक्षणेष्वञ्यञिञामण् । ४ । ३ । १२७ । 'घोषग्रहणमपि कर्तव्यम्' (वा २९१५) । अञ् । बैदः संघोऽङ्को घोषो वा । बैदं लक्षणम् । यञ् । गार्गः—गार्गम् । इञ् । दाक्षः—दाक्षम् । परम्परासंबन्धोऽङ्कः । साक्षात्तु लक्षणम् ।

१५०८ । शाकलाद्वा । ४ । ३ । १२८ । अण्वोक्तेऽर्थे । पक्षे चरणात्वाद्वुञ् । शकलेन प्रोक्तमधीयते शाकलास्तेषां संघोऽङ्को घोषो वा शाकलः—शाकलकः । लक्षणे क्लीबता ।

१५०९ । छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः । ४ । ३ । १२९ । छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् । 'चरणाद्धर्माम्नाययोः' (वा २९१३) इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ।

१५१० । न दण्डमाणवान्तेवासिषु । ४ । ३ । १३० । दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ्न स्यात् । दाक्षा दण्डमाणवाः शिष्या वा ।

१५११ । रैवतिकादिभ्यश्छः । ४ । ३ । १३१ । तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ।

१५१२ । कौपिञ्जलहास्तिपदादण् । ४ । ३ । १३२ । (वा २९१८) । कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् । तदन्तात्पुनरण् । कौपिञ्जलः । गोत्रवुञोऽपवादः । हस्तिपदस्यापत्यं हास्तिपदस्तस्यायं हास्तिपदः ।

---

१ 'अपाणिनीयः सूत्रेषु पाठः' इति कैयटः ।

१५१३ । [1]आथर्वणिकस्येकलोपश्च । ४ । ३ । १३३ । अण्स्यात् । आथर्वणिकस्याय-मार्थर्वणो धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ।

इति तद्धितशैषिकप्रकरणम् ।

अथ तद्धितप्राग्दीव्यतीयप्रकरणम् ।

१५१४ । तस्य विकारः । ४ । ३ । १३४ । 'अश्मनो विकारे टिलोपो वक्तव्यः' (वा ४१८५) । अश्मनो विकार आश्मः । भास्मनः । मार्त्तिकः ।

१५१५ । अवयवे च प्राण्योषधिवृक्षेभ्यः । ४ । ३ । १३५ । चाद्विकारे । मयूरस्याव-यवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ।

१५१६ । बिल्वादिभ्योऽण् । ४ । ३ । १३६ । बैल्वम् ।

१५१७ । कोपधाच्च । ४ । ३ । १३७ । अण् । अञोऽपवादः । तर्कु—तार्कवम् तैत्तिडीकम् ।

१५१८ । त्रपुजतुनोः षुक् । ४ । ३ । १३८ । आभ्यामण्स्याद्विकारे, एतयोः षुगागमश्च त्रापुषम् । जातुषम् ।

१५१९ । ओरञ् । ४ । ३ । १३९ । दैवदारवम् । भाद्रदारवम् ।

१५२० । अनुदात्तादेश्च । ४ । ३ । १४० । दाधित्थम् । कापित्थम् ।

१५२१ । पलाशादिभ्यो वा । ४ । ३ । १४१ । पालाशम् । खादिरम् । कारीरम् ।

१५२२ । शम्याः ष्लञ् । ४ । ३ । १४२ । शामीलं भस्म । षित्वान्ङीष् । शामीली स्रुक्

१५२३ । मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । ४ । ३ । १४३ । प्रकृतिमात्रान्-मयड्वा स्याद्विकारावयवयोः । अश्ममयम् –आश्मनम् । 'अभक्ष्य–'इत्यादि किम् । मौद्गः सूपः कार्पासमाच्छादनम् ।

१५२४ । नित्यं वृद्धशरादिभ्यः । ४ । ३ । १४४ । आम्रमयम् । शरमयम् । '[2]एकाचो नित्यम्' (वा ५०९२) । त्वङ्मयम् । वाङ्मयम् । कथं तर्हि 'आप्यम्' 'अम्मयम्' इति 'तस्येदम्' (सू १५००) इत्यण्णन्तात्स्वार्थे ष्यञ् ।

१५२५ । गोश्च पुरीषे । ४ । ३ । १४५ । गोः पुरीषं गोमयम् ।

१५२६ । पिष्टाच्च । ४ । ३ । १४६ । मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां 'तस्येदम्' (सू १५००) इत्यण् ।

१५२७ । संज्ञायां कन् । ४ । ३ । १४७ । 'पिष्टात्' इत्येव । पिष्टस्य विकारविशेषः पिष्टकः । 'पूपोऽपूपः पिष्टकः स्यात्' इत्यमरः ।

१५२८ । व्रीहेः पुरोडाशे । ४ । ३ । १४८ । मयट् स्यात् । बिल्वाद्यणोऽपवादः । व्रीहिमयः पुरोडाशः । व्रैहमन्यत् ।

---

१ इदं सूत्रमिति कैयटः । 'इदमपि वार्तिकमेवेति हरदत्तः' इति विवरणे नागेशः । युक्तं च वार्तिकत्वमेव । सूत्रत्वे चकारेण वार्तिकस्थस्याणः संग्रहस्य क्लिष्टत्वात् । २ आरम्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणेनान्यार्थकेनेदं सिद्धम् ।

१५२९। असंज्ञायां तिलयवाभ्याम्। ४। ३। १४९। तिलमयम्। यवमयम्। संज्ञायां तु तैलम्। यावकः।

१५३०। तालादिभ्योऽण्। ४। ३। १५२। अञ्मयटोरपवादः। 'तालाद्धनुषि' (ग सू १९४)। तालं धनुः। अन्यत्तालमयम्। ऐन्द्रायुधम्।

१५३१। जातरूपेभ्यः परिमाणे। ४। ३। १५३। अण्। बहुवचनात्पर्यायग्रहणम्। हाटकः। तापनीयः सौवर्णो वा निष्कः। 'परिमाणे' किम्। हाटकमयी यष्टिः।

१५३२। प्राणिरजतादिभ्योऽञ्। ४। ३। १५४। शौकम्। बाकम्। राजतम्।

१५३३। ञितश्च तत्प्रत्ययात्। ४। ३। १५५। ञितो विकारावयवप्रत्ययस्तदन्तादञ्स्यात्तयोरेवार्थयोः। मयटोऽपवादः। शामीलस्य शामीलम्। दाधित्थस्य दाधित्थम्। कापित्थम्। 'ञितः' किम्। बैल्वमयम्।

१५३४। क्रीतवत्परिमाणात्। ४। ३। १५६। 'प्राग्वहतेष्ठक्' (सू १५४८) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते। अणादीनामपवादः। निष्केण क्रीतं नैष्किकम्। एवं निष्कस्य विकारोऽपि नैष्किकः। शतस्य विकारः शत्यः—शतिकः।

१५३५। उष्ट्राद्वुञ्। ४। ३। १५७। प्राण्यञोऽपवादः। औष्ट्रकः।

१५३६। उमोर्णयोर्वा। ४। ३। १५८। औमम्—औमकम्। और्णम्—और्णकम् वुञभावे यथाक्रममणञौ।

१५३७। एण्या ढञ्। ४। ३। १५९। ऐणेयम्। एणस्य तु ऐणम्।

१५३८। गोपयसोर्यत्। ४। ३। १६०। गव्यम्। पयस्यम्।

१५३९। द्रोश्च। ४। ३। १६१। द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम्।

१५४०। माने वयः। ४। ३। १६२। 'द्रोः' इत्येव। द्रुवयम्। 'पौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम्' इत्यमरः।

१५४१। फले लुक्। ४। ३। १६३। विकारावयवप्रत्ययस्य लुक्स्यात्फले। आमलक्याः फलमामलकम्।

१५४२। प्लक्षादिभ्योऽण्। ४। ३। १६४। विधानसामर्थ्यान्न लुक्। प्लाक्षम्।

१५४३। न्यग्रोधस्य च केवलस्य। ७। ३। ५। अस्य न वृद्धिरैजागमश्च। नैयग्रोधम्।

१५४४। जम्ब्वा वा। ४। ३। १६५। जम्बूशब्दात्फलेऽण्वा स्यात्। जाम्बवम्। पक्षे ओरञ्। तस्य लुक्। जम्बु।

१५४५। लुप्च। ४। ३। १६६। जम्ब्वाः फलप्रत्ययस्य लुब्वा स्यात्। 'लुपि युक्तवत्—' (सू १२९४)। जम्ब्वाः फलं जम्बूः। 'फलपाकशुषामुपसंख्यानम्' (वा २९४९)। व्रीहयः। मुद्गाः। 'पुष्पमूलेषु बहुलम्' (वा २९५०)। मल्लिकायाः पुष्पं मल्लिका। जात्याः पुष्पं जाती। विदार्या मूलं विदारी। बहुलग्रहणान्नेह। पाटलानि पुष्पाणि। साल्वानि मूलानि। बाहुलकात्क्वचिल्लुक्। अशोकम्। करवीरम्।

१५४६ । हरीतक्यादिभ्यश्च । ४ । ३ । १६७ । एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरी-तक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ।

१५४७ । कंसीयपरशव्ययोर्यञञौ लुक्च । ४ । ३ । १६८ । कंसीयपरशव्य-शब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम् । तस्य विकारः कांस्यम् । पर-शवे हितं परशव्यम् । तस्य विकारः पारशवः ।

इति तद्धितप्राग्दीव्यतीयप्रकरणम् ।

अथ तद्धितठगधिकारप्रकरणम् ।

१५४८ । प्राग्वहतेष्ठक् । ४ । ४ । १ । तद्वहतीत्यतः प्राक् ठगधिक्रियते । 'तदा-माशब्दादिभ्य उपसंख्यानम्' (वा २९९१) । माशब्दः कारि इति य आह स माशब्दिकः ।

१५४९ । स्वागतादीनां च । ७ । ३ । ७ । ऐज्न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वाङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः । व्यव-हारेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् । 'आहौ प्रभूतादिभ्यः' (वा २९९२) प्रभूतमाह प्राभूतिकः । पार्यातिकः । 'पृच्छतौ सुस्नातादिभ्यः' (वा २९९३) । सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः । 'गच्छतौ परदारादिभ्यः' (वा २९९४) । पारदारिकः । गौरुतल्पिकः ।

१५५० । तेन दीव्यति खनति जयति जितम् । ४ । ४ । २ । अक्षैर्दी-व्यति आक्षिकः । अभ्र्या खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ।

१५५१ । संस्कृतम् । ४ । ४ । ३ । दध्ना संस्कृतं दाधिकम् । मारिचिकम् ।

१५५२ । कुलत्थकोपधादण् । ४ । ४ । ४ । ठकोऽपवादः । कुलत्थैः संस्कृतं कौल-त्थम् । तैत्तिडीकम् ।

१५५३ । तरति । ४ । ४ । ५ । उडुपेन तरति औडुपिकः ।

१५५४ । गोपुच्छाट्ठञ् । ४ । ४ । ६ । गौपुच्छिकः ।

१५५५ । नौद्व्यचष्ठन् । ४ । ४ । ७ । नाविकः । घटिकः । बाहुभ्यां तरति बा-हुका स्त्री ।

१५५६ । चरति । ४ । ४ । ८ । तृतीयान्ताद्गच्छतिभक्षयतीत्यर्थयोष्ठक्स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ।

१५५७ । आकर्षात्ष्ठल् । ४ । ४ । ९ । आकर्षो निकषोपलः । 'आकषात्' इति पाठान्तरम् । तेन चरति आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ।

१५५८ । पर्पादिभ्यः ष्ठन् । ४ । ४ । १० । पर्पेण चरति पर्पिकः-पर्पिकी । येन पी-ठेन पङ्गवश्चरन्ति स पर्पः । आश्विकः । रथिकः ।

१५५९ । श्वगणाट्ठञ्च । ४ । ४ । ११ । चात्ष्ठन् ।

१५६० । श्वादेरिञि । ७ । ३ । ८ । ऐज्न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्ट्रिः । तदा-दिविधौ चेदमेव ज्ञापकम् । 'इकारादाविति वाच्यम्' (वा ४९१२) । श्वगणेन चरति श्वा-गणिकः-श्वागणिकी-श्वगणिकः- श्वगणिकी ।

१५६१। पदान्तस्यान्यतरस्याम्।७।३।९ श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा। श्वापदस्येदं श्वापदम्–शौवापदम्।

१५६२। वेतनादिभ्यो जीवति।४।४।१२। वेतनेन जीवति वैतनिकः। धानुष्कः।

१५६३। वस्नक्रयविक्रयाट्ठन्।४।४।१३। वस्नेन मूल्येन जीवति वास्निकः। क्रयविक्रयग्रहणं संघातविगृहीतार्थम्। क्रयविक्रयिकः–क्रयिकः–विक्रयिकः।

१५६४। आयुधाच्छ च।४।४।१४। चाट्ठन्। आयुधेन जीवति आयुधीयः–आयुधिकः।

१५६५। हरत्युत्सङ्गादिभ्यः।४।४।१५। उत्सङ्गेन हरत्यौत्सङ्गिकः।

१५६६। भस्त्रादिभ्यः ष्ठन्। ४।४। १६। भस्त्रया हरति भस्त्रिकः। षित्वान्ङीष्। भस्त्रिकी।

१५६७। विभाषा विवधात्।४।४। १७। विवधेन हरति विवधिकः। पक्षे ठक्। वैवधिकः। एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन्। वीवधिकः वीवधिकी। विवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते।

१५६८। अण्कुटिलिकायाः।४।४।१८। कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च। कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च।

१५६९। निर्वृत्तेऽक्षद्यूतादिभ्यः।४।४।१९। अक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं वैरम्।

१५७०। त्रेर्मम्नित्यम्।४।४।२०। त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थेमप्स्यान्नित्यम्। कृत्या निर्वृत्तं कृत्रिमम्। पक्त्रिमम्। 'भावप्रत्ययान्तादिमब्वक्तव्यः' (वा २९९९) पाकेन निर्वृत्तं पाकिमम्। त्यागिमम्।

१५७१। अपमित्ययाचिताभ्यां कक्कनौ।४।४।२१। अपमित्येति ल्यबन्तम्। अपमित्य निर्वृत्तमापमित्यकम्। याचितेन निर्वृत्तं याचितकम्।

१५७२। संसृष्टे।४।४।२२। दध्ना संसृष्टं दाधिकम्।

१५७३। चूर्णादिनिः।४।४।२३। चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः।

१५७४। लवणाल्लुक्।४।४।२४। लवणेन संसृष्टो लवणः सूपः। लवणं शाकम्।

१५७५। मुद्गादण्।४।४।२५। मौद्ग ओदनः।

१५७६। व्यञ्जनैरुपसिक्ते।४।४।२६। ठक्। दध्ना उपसिक्तं दाधिकम्।

१५७७। ओजःसहोऽम्भसा वर्तते।४।४।२७। ओजसा वर्तते औजसिकः शूरः। साहसिकश्चौरः। आम्भसिको मत्स्यः।

१५७८। तत्प्रत्यनुपूर्वमीपलोमकूलम्।४।४।२८। द्वितीयान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक्स्यात्। क्रियाविशेषणत्वाद्द्वितीया। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः। प्रातिलोमिकः। आनुलोमिकः। प्रातिकूलिकः। आनुकूलिकः।

१५७९। परिमुखं च।४।४।२९। परिमुखं वर्तते पारिमुखिकः। चात्पारिपार्श्विकः।

१५८०। प्रयच्छति गर्ह्यम्।४।४।३०। द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः। त्रैगुणिकः। 'वृद्धेर्वृधुषिभावो वक्तव्यः' (वा २९६९)। वार्धुषिकः।

१५८१। कुसीददशैकादशात्ष्ठन्ष्ठचौ।४।४।३१। गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः

प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छतीति कुसीदिकः-कुसीदि एकादशार्थत्वादेकादश ते च ते वस्तुतो दश चेति विग्रहेऽकारः समासान्त इहैव सूत्रे नि त्यते । दशैकादशिकः-दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितः ।

१५८२ । उञ्छति । ४ । ४ । ३२ । बदराण्युञ्छति बादरिकः ।

१५८३ । रक्षति । ४ । ४ । ३३ । समाजं रक्षति सामाजिकः ।

१५८४ । शब्ददर्दुरं करोति । ४ । ४ । ३४ । शब्दं करोति शाब्दिकः । दार्दुरि

१५८५ । पक्षिमत्स्यमृगान्हन्ति । ४ । ४ । ३५ । 'स्वरूपस्य (पर्यायाणां) विशे ग्रहणम्' (वा ९२३) । 'मत्स्यपर्यायेषु मीनस्यैव' (भाष्येष्टिः) । पक्षिणो हन्ति पाक्षि शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः। शाकुनिकः।मार्गिकः। हारिणिकः । सारङ्गि

१५८६ । परिपन्थं च तिष्ठति । ४ । ४ । ३६ । अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चे ठक्स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पन्थिकः ।

१५८७ । माथोत्तरपदपदव्यनुपदं धावति । ४ । ४ । ३७ । दण्डाकारो माथः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ।

१५८८ । आक्रन्दाट्ठञ्च । ४ । ४ । ३८ । अस्माट्ठक्स्यात्, चाट्ठक् । धावतीत आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रंन्दिकः ।

१५८९ । पदोत्तरपदं गृह्णाति । ४ । ४ । ३९ । पूर्वपदं गृह्णाति पौर्वपदिकः । औ रपदिकः ।

१५९० । प्रतिकण्ठार्थललामं च । ४ । ४ । ४० । एभ्यो गृह्णात्यर्थे ठक् प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः ।

१५९१ । धर्मं चरति । ४ । ४ । ४१ । धार्मिकः । 'अधर्माच्चेति वक्तव्यम् २९६६) । आधर्मिकः ।

१५९२ । प्रथिपथमेति ठंश्च । ४ । ४ । ४२ । प्रतिपथमेति प्रातिपथिकः ।

१५९३ । समवायान्समवैति । ४ । ४ । ४३ । सामवायिकः । सामूहिकः ।

१५९४ । परिषदो ण्यः । ४ । ४ । ४४ । परिषदं समवैति पारिषद्यः ।

१५९५ । सेनाया वा । ४ । ४ । ४५ । ण्यः स्यात् । पक्षे ठक् । सैन्याः-सैनि

१५९६ । संज्ञायां ललाटकुक्कुट्यौ पश्यति । ४ । ४ । ४६ । ललाटं प लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पाताहः स्वल्पदेशो लक्ष्यते । कौक्कुटिको भिक्षु

१५९७ । तस्य धर्म्यम् । ४ । ४ । ४७ । आपणस्य धर्म्यमापणिकम् ।

१५९८ । अण्महिष्यादिभ्यः । ४ । ४ । ४८ । महिष्या धर्म्यं माहिषम् जमानम् ।

१५९९ । ऋतोऽञ् । ४ । ४ । ४९ । यातुर्धर्म्यं यात्रम् । 'नराच्चेति वक्तव्यम् २९६७) । नरस्य धर्म्या नारी । 'विशसितुरिड्लोपश्चाञ्च वक्तव्यः' (वा २९६८) । वि धर्म्यं वैशसम् । 'विभाजयितुर्णिलोपश्चाञ्च वाच्यः' (वा २९६९) । विभाजयि वैभाजित्रम् ।

१६००। अवक्रयः। ४। ४। ५०। षष्ठ्यन्ताट्ठक्स्यादवक्रयेऽर्थे। आपणस्यावक्रय आपणिकः। राजग्राह्यं द्रव्यमवक्रयः।

१६०१। तदस्य पण्यम्। ४। ४। ५१। अपूपाः पण्यमस्य आपूपिकः।

१६०२। लवणाट्ठञ्। ४। ४। ५२। लावणिकः।

१६०३। किसरादिभ्यः ष्ठन्। ४। ४। ५३। किसरं पण्यमस्य किसरिकः। षित्वान्ङीष्। किसरिकी। किसर। उशीर। नलद। इत्यादिकिसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः।

१६०४। शलालुनोऽन्यतरस्याम्। ४। ४। ५४। ष्ठन्स्यात्। पक्षे ठक्। शलालुकः–शलालुकी–शालालुकः–शालालुकी। शलालुः सुगन्धिद्रव्यविशेषः।

१६०५। शिल्पम्। ४। ४। ५५। मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः।

१६०६। मड्डुकझर्झरादणन्यतरस्याम्। ४। ४। ५६। मड्डुकवादनं शिल्पमस्य माड्डुकः–माड्डुकिकः। झार्झरः–झार्झरिकः।

१६०७। प्रहरणम्। ४। ४। ५७। 'तदस्य' इत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः।

१६०८। परश्वधाट्ठञ्च। ४। ४। ५८। पारश्वधिकः।

१६०९। शक्तियष्ट्योरीकक्। ४। ४। ५९। शाक्तीकः। याष्टीकः।

१६१०। अस्तिनास्तिदिष्टं मतिः। ४। ४। ६०। 'तदस्य' इत्येव। अस्ति परलोक इत्येवं मतिर्यस्य स आस्तिकः। नास्तीति मतिर्यस्य स नास्तिकः। दिष्टमिति मतिर्यस्य स दैष्टिकः।

१६११। शीलम्। ४। ४। ६१। अपूपभक्षणं शीलमस्य आपूपिकः।

१६१२। छत्रादिभ्यो णः। ४। ४। ६२। गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्त्रः।

१६१३। कार्मस्ताच्छील्ये। ६। ४। १७२। कार्म इति ताच्छील्ये णे टिलोपो निपात्यते। कर्मशीलः कार्मः। 'नस्तद्धिते' (सू ६७९) इत्येव सिद्धे 'अण्कार्यं ताच्छीलिके णेऽपि'। चौरी तापसीत्यादि सिद्धम्। 'ताच्छील्ये' किम्। कार्मणः।

१६१४। कर्माध्ययने वृत्तम्। ४। ४। ६३। प्रथमान्तात्षष्ठ्यर्थे ठक्स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः। ऐकान्यिकः। यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः।

१६१५। बह्वच्पूर्वपदाट्ठच्। ४। ४। ६४। प्राग्विषये। द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः। द्वादशापपाठा अस्य जाता इत्यर्थः।

१६१६। हितं भक्षाः। ४। ४। ६५। अपूपभक्षणं हितमस्मा आपूपिकः।

१६१७। तदस्मै दीयते नियुक्तम्। ४। ४। ६६। अग्रभोजनं नियतं दीयते अस्मा आग्रभोजनिकः।

१६१८। श्राणामांसौदनाट्टिठन्। ४। ४। ६७। श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः–श्राणिकी। मांसौदनग्रहणं संघातविगृहीतार्थम्। मांसौदनिकः–मांसिकः–औदनिकः।

१६१९ । भक्तादणन्यतरस्याम् । ४ । ४ । ६८ । पक्षे ठक् । भक्तमस्मै नियुक्तं दी
भाक्तः—भाक्तिकः ।

१६२० । तत्र नियुक्तः । ४ । ४ । ६९ । आकरे नियुक्त आकरिकः ।

१६२१ । अगारान्ताट्ठन् । ४ । ४ । ७० । देवागारे नियुक्तो देवागारिकः ।

१६२२ । अध्यायिन्यदेशकालात् । ४ । ४ । ७१ । निषिद्धदेशकालवाचकाट्ठक्स्या
तरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः ।

१६२३ । कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति । ४ । ४ । ७२ । 'तत्र' इ
वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठि
तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानि

१६२४ । निकटे वसति । ४ । ४ । ७३ । नैकटिको भिक्षुः ।

१६२५ । आवसथात्ष्ठल् । ४ । ४ । ७४ । आवसथे वसति आवसथिकः । षित्त्वा
आवसथिकी ।

'आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च ।
आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥' (वा २९९९)

षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ।

इति तद्धितठगधिकारप्रकरणम् ।

अथ तद्धितप्राग्घितीयप्रकरणम् ।

१६२६ । प्राग्घिताद्यत् । ४ । ४ । ७५ । 'तस्मै हितम्' (सू १६६५) इत्यतः प्रा
धिक्रियते ।

१६२७ । तद्वहति रथयुगप्रासङ्गम् । ४ । ४ । ७६ । रथं वहति रथ्यः । यु
वत्सानां दमनकाले स्कन्धे यत्काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ।

१६२८ । धुरो यड्ढकौ । ४ । ४ । ७७ । 'हलि च' (सू ३५४) इति दीर्घे प्राप्ते ।

१६२९ । न भकुर्छुराम् । ८ । २ । ७९ । भस्य कुर्छुरोश्चोपधाया दीर्घो न ।
धुर्यः—धौरेयः ।

१६३० । खः सर्वधुरात् । ४ । ४ । ७८ । सर्वधुरं वहतीति सर्वधुरीणः ।

१६३१ । एकधुराल्लुक्च । ४ । ४ । ७९ । एकधुरं वहति एकधुरीणः— एकधुरः

१६३२ । शकटादण् । ४ । ४ । ८० । शकटं वहति शाकटो गौः ।

१६३३ । हलसीराट्ठक् । ४ । ४ । ८१ । हलं वहति हालिकः । सैरिकः ।

१६३४ । संज्ञायां जन्या । ४ । ४ । ८२ । जनी वधूः । तां वहति प्रापयति ज

१६३५ । विध्यत्यधनुषा । ४ । ४ । ८३ । द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न
धनुष्करणम् । पादौ विध्यन्ति पद्याः शर्कराः ।

१६३६ । धनगणं लब्धा । ४ । ४ । ८४ । तृन्नन्तमेतत् । धनं लब्धा धन्यः ।
लब्धा गण्यः ।

१६३७ । अन्नाण्णः । ४ । ४ । ८५ । अन्नं लब्धा आन्नः ।

१६३८ । वशं गतः । ४ । ४ । ८६ । वश्यः परेच्छानुचारी ।

१६३९ । पदमस्मिन्दृश्यम् । ४ । ४ । ८७ । पद्यः कर्दमः । नातिशुष्क इत्यर्थः ।

१६४० । मूलमस्याबर्हि । ४ । ४ । ८८ । आवर्हणमाबर्हं उत्पाटनं तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः ।

१६४१ । संज्ञायां धेनुष्या । ४ । ४ । ८९ । धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते संज्ञायाम् । 'धेनुष्या बन्धके स्थिता' इत्यमरः ।

१६४२ । गृहपतिना संयुक्ते ञ्यः । ४ । ४ । ९० । गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्निः ।

१६४३ । नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु । ४ । ४ । ९१ । नावा तार्यं नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेनानाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ।

१६४४ । धर्मपथ्यर्थन्यायादनपेते । ४ । ४ । ९२ । धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ।

१६४५ । छन्दसो निर्मिते । ४ । ४ । ९३ । छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ।

१६४६ । उरसोऽण्च । ४ । ४ । ९४ । चाद्यत् । उरसा निर्मितः पुत्र औरसः– उरस्यः ।

१६४७ । हृदयस्य प्रियः । ४ । ४ । ९५ । हृद्यो देशः । 'हृदयस्य हृल्लेख–' (सू ९८८) इति हृदादेशः ।

१६४८ । बन्धने चर्षौ । ४ । ४ । ९६ । हृदयशब्दात्षष्ठ्यन्ताद्बन्धने यत्स्यादृषेदेऽभिधेये हृदयस्य बन्धनं हृद्यो वशीकरणमन्त्रः ।

१६४९ । मतजनहलात्करणजल्पकर्षेषु । ४ । ४ । ९७ । मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्षो हल्यः ।

१६५० । तत्र साधुः । ४ । ४ । ९८ । अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । 'ये चाभावकर्मणोः' (सू ११५४) इति प्रकृतिभावः । कर्मण्यः । शरण्यः ।

१६५१ । प्रतिजनादिभ्यः खञ् । ४ । ४ । ९९ । प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः ।

१६५२ । भक्ताण्णः । ४ । ४ । १०० । भक्ते साधवो भाक्ताः शालयः ।

१६५३ । परिषदो ण्यः । ४ । ४ । १०१ । पारिषद्यः । 'परिषदः' इति योगविभागाण्णोऽपि । पारिषदः । ['पर्षदः' इति पाठान्तरम् । पार्षदः ।]

१६५४ । कथादिभ्यष्ठक् । ४ । ४ । १०२ । कथायां साधुः काथिकः ।

१६५५ । गुडादिभ्यष्ठञ् । ४ । ४ । १०३ । गुडे साधुर्गौडिक इक्षुः । साक्तुको यवः ।

१६५६ । पथ्यतिथिवसतिस्वपतेर्ढञ् । ४ । ४ । १०४ । पथि साधु पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ।

---

१ 'स पार्षदैरम्बरमापुपूरे' इति जाम्बवतीजये पाणिनिः–इति मुकुटः ।

१६५७ । सभाया यः । ४ । ४ । १०६ । सभ्यः ।

१६५८ । समानतीर्थे वासी । ४ । ४ । १०७ । 'साधुः' इति निवृत्तम् । वसतीति वा समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ।

१६५९ । समानोदरे शयित ओ चोदात्तः । ४ । ४ । १०८ । समाने उदरे शे स्थितः समानोदर्यो भ्राता ।

१६६० । सोदराद्यः । ४ । ४ । १०९ । सोदर्यः । अर्थः प्राग्वत् ।

इति तद्धितप्राग्घितीयप्रकरणम् ।

अथ तद्धितछयद्विधिप्रकरणम् ।

१६६१ । प्राक् क्रीताच्छः । ५ । १ । १ । 'तेन क्रीतम्' (सू १७०२) इत्यतः छोऽधिक्रियते ।

१६६२ । उगवादिभ्यो यत् । ५ । १ । २ । प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादेः यत्स्याच्छस्यापवादः । 'नाभि नभं च' (ग सू ९५) । नभ्योऽक्षः । नभ्यमञ्जनम् । रथना वेदम् । 'शुनः संप्रसारणं वा च दीर्घत्वम्' (ग सू ९६) । शून्यम्-शुन्यम् । 'ऊधसोऽन (ग सू ९७) । ऊधन्यः ।

१६६३ । कम्बलाच्च संज्ञायाम् । ५ । १ । ३ । यत्स्यात् । कम्बल्यमूर्णापलशत 'संज्ञायाम्' किम् । कम्बलीयोर्णा ।

१६६४ । विभाषा हविरपूपादिभ्यः । ५ । १ । ४ । आमिक्ष्यं दधि आमिक्षीयम् । डाश्यास्तण्डुलाः पुरोडाशीयाः । अपूप्यम्-अपूपीयम् ।

१६६५ । तस्मै हितम् । ५ । १ । ५ । वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे शङ्कव्यं दारु । गव्यम् । हविष्यम् ।

१६६६ । शरीरावयवाद्यत् । ५ । १ । ६ । दन्त्यम् । कण्ठ्यम् । 'नस्नासिकायाः ३४९७) । नस्यम् । नाभ्यम् ।

१६६७ । ये च तद्धिते । ६ । १ । ६१ । यादौ तद्धिते परे शिरःशब्दस्य शीर्षन्नादे स्यात् । शीर्षण्यः । 'तद्धिते' किम् । शिर इच्छति शिरस्यति । 'वा केशेषु' (वा ३४९ शीर्षण्याः-शिरस्या वा केशाः । 'अचि शीर्ष इति वाच्यम्' (वा ३४९४) । अजादौ त शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ।

१६६८ । खलयवमाषतिलवृषब्रह्मणश्च । ५ । १ । ७ । खलाय हितं खल्यम् । यव माष्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ।

१६६९ । अजाविभ्यां थ्यन् । ५ । १ । ८ । अजथ्या यूथिः । अविथ्या ।

१६७० । आत्मन्विश्वजनभोगोत्तरपदात्खः । ५ । १ । ९ ।

१६७१ । आत्माध्वानौ खे । ६ । ४ । १६९ । एतौ खे प्रकृत्या स्तः । आत्मने हि त्मनीनम् । विश्वजनीनम् । 'कर्मधारयादेवेष्यते' । षष्ठीतत्पुरुषाद्बहुव्रीहेश्च एव । विश्व यम् । 'पञ्चजनादुपसंख्यानम्' (वा २९९६) । पञ्चजनीनम् । 'सर्वजनाट्ठञ् खश्च' (वा २९

सार्वजनिकः—सर्वजनीनः । 'महाजनाट्ठञ्' (वा २९९८) । माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीनः । 'आचार्यादणत्वं च' (ग सू १८४) । आचार्यभोगीनः ।

१६७२ । सर्वपुरुषाभ्यां णढञौ । ५ । १ । १० । 'सर्वाण्णो वेति वक्तव्यम्' (वा २९९९) । सर्वस्मै हितं सार्वम्–सर्वीयम् । 'पुरुषाद्वधविकारसमूहतेनकृतेषु' (वा ३०००) । भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । 'तस्येदम्' (सू १५००) इत्याणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । 'प्राणिरजतादिभ्योऽञ्' (सू १५३२) इत्यञि प्राप्ते । समूहेऽप्यणि प्राप्ते । 'एकाकिनोऽपि परितः पौरुषेयवृता इव' इति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ।

१६७३ । माणवचरकाभ्यां खञ् । ५ । १ । ११ । माणवाय हितं माणवीनम् । चारकीणम् ।

१६७४ । तदर्थं विकृतेः प्रकृतौ । ५ । १ । १२ । विकृतिवाचकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गारेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ।

१६७५ । छदिरुपधिबलेर्ढञ् । ५ । १ । १३ । छादिषेयाणि तृणानि । बालेयास्तण्डुलाः । 'उपधिशब्दात्स्वार्थे इष्यते' (वा ३००३) । उपधीयेत इत्युपधी रथाङ्गं तदेव औपधेयम् ।

१६७६ । ऋषभोपानहोर्ञ्यः । ५ । १ । १४ । छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन । औपानह्यं चर्म ।

१६७७ । चर्मणोऽञ् । ५ । १ । १५ । चर्मणो या विकृतिस्तद्वाचकादञ्स्यात् । वध्र्यै इदं वार्ध्रं चर्म । वारत्रं चर्म ।

१६७८ । तदस्य तदस्मिन्स्यादिति । ५ । १ । १६ । प्राकार आसामिष्टकानां स्यात्प्राकारीया इष्टकाः । प्रासादीयं दारु । प्राकारोऽस्मिन्स्यात्प्राकारीयो देशः । इतिशब्दो लौकिकीं विवक्षामनुसारयाति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ।

१६७९ । परिखाया ढञ् । ५ । १ । १७ । पारिखेयी भूमिः ।

इति तद्धितछयद्विधिप्रकरणम् ।

अथ तद्धितार्हीयप्रकरणम् ।

१६८० । प्राग्वतेष्ठञ् । ५ । १ । १८ । 'तेन तुल्यम्–' (सू १७७८) इति वतिं वक्ष्यति ततः प्राक्ठञधिक्रियते ।

१६८१ । आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् । ५ । १ । १९ । 'तदर्हति' (सू १७२८) इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ।

१६८२ । असमासे निष्कादिभ्यः । ५ । १ । २० । 'आर्हात्' इत्येतत् 'तेन क्रीतम्' (सू १७०२) इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु नैष्किकम् । समासे तु ठञ् ।

१६८३ । परिमाणान्तस्यासंज्ञाशाणयोः । ७ । ३ । १७ । उत्तरपदवृद्धिः स्यात् ञिदादौ ।

परमनैष्किकः। 'असंज्ञा' इति किम्। पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकः। 'तदस्य परिमाणम्' (सू १७२३) इति ठञ्। असमासग्रहणं ज्ञापकं भवति 'इत्यतः प्राक् तदन्तविधिः' इति। तेन सुगन्ध्यम्—यवापूप्यमित्यादि। इत ऊर्ध्वं तु 'संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि—' (वा ३०१८)। पारायणिकः। द्वैपारायणिकः। 'अलुकि' इति किम्। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्। द्विशूर्पेण क्रीते 'शूर्पादञ्—' (सू १६९१) मा भूत्, किं तु ठञ्। द्विशौर्पिकम्।

१६८४। अर्धात्परिमाणस्य पूर्वस्य तु वा। ७। ३। २६। अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा ञिति णिति किति च। अर्धद्रोणेन क्रीतमर्धद्रौणिकम्--आर्धद्रौणिकम्।

१६८५। नातः परस्य। ७। ३। २७। अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वस्य तु वा ञिदादौ। अर्धप्रस्थिकम्—आर्धप्रस्थिकम्। 'अतः' किम्। आर्धकौडविकम्। अर्धखार्यां भवा अर्धखारी। अर्धखारीभार्य इत्यत्र 'वृद्धिनिमित्तस्य'—(सू ८४०) इति पुंवद्भावनिषेधो न स्यात्।

१६८६। शताच्च ठन्यतावशते। ५। १। २१। शतेन क्रीतं शतिकम्—शत्यम्। 'अशते' किम्। शतं परिमाणमस्य शतकः संघः। इह प्रत्ययार्थो वस्तुतः प्रकृत्या भिद्यते, तेन ठन्यतौ न। किं तु कनेव। 'असमासे' इत्येव। द्विशतेन क्रीतं द्विशतकम्।

१६८७। संख्याया अतिशदन्तायाः कन्। ५।१।२२। संख्यायाः कन्स्यादार्हीये न तु त्यन्तशदन्तायाः। पञ्चभिः क्रीतः पञ्चकः। बहुकः। त्यन्तायास्तु साप्ततिकः। शदन्तायाः। चात्वारिंशत्कः।

१६८८। वतोरिड्वा। ५। १। २३। वत्वन्तात्कन इड्वा स्यात्। तावतिकः—तावत्कः।

१६८९। विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्। ५। १। २४। योगविभागः कर्तव्यः। आभ्यां कन्स्यात्। असंज्ञायां ड्वुन्स्यात्। कनोऽपवादः। विंशकः। त्रिंशकः। संज्ञायां तु विंशतिकः। त्रिंशतिकः।

१६९०। कंसाट्टिठन्। ५। १। २५। टो ङीबर्थः। इकार उच्चारणार्थः। कंसिकः—कंसिकी। 'अर्धाच्चेति वक्तव्यम्' (वा ३०१८)। अर्धिकः—अर्धिकी। 'कार्षापणाट्टिठन्वक्तव्यः प्रतिरादेशश्च वा' (वा ३०१९)। कार्षापणिकः—कार्षापणिकी। प्रतिकः—प्रतिकी।

१६९१। शूर्पादञन्यतरस्याम्। ५। १। २६। शौर्पम्—शौर्पिकम्।

१६९२। शतमानविंशतिकसहस्रवसनादण्। ५। १। २७। एभ्योऽण्स्यात्। ठञ्ठकनामपवादः। शतमानेन क्रीतं शातमानम्। वैंशतिकम्। साहस्रम्। वासनम्।

१६९३। अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्। ५। १। २८। अध्यर्धपूर्वाद्द्विगोश्च परस्यार्हीयस्य लुक्स्यात्। अध्यर्धकंसम्। द्विकंसम्। संज्ञायां तु पाञ्चकलापिकम्।

१६९४। विभाषा कार्षापणसहस्राभ्याम्। ५। १। २९। लुग्वा स्यात्। अध्यर्धकार्षापणम्—अध्यर्धकार्षापणिकम्। द्विकार्षापणम्—द्विकार्षापणिकम्। औपसंख्यानिकस्य टिठनो लुक्। पक्षेऽध्यर्धप्रतिकम्। द्विप्रतिकम्। अध्यर्धसहस्रम्—अध्यर्धसाहस्रम्। द्विसहस्रम्—द्विसाहस्रम्।

१६९५ । द्वित्रिपूर्वान्निष्कात् । ५ । १ । ३० । लुग्वा स्यात् । द्विनिष्कम्–द्विनैष्किकम् । त्रिनिष्कम्–त्रिनैष्किकम् । 'बहुपूर्वाच्चेति वक्तव्यम्' (वा ३०२४) । बहुनिष्कम्–बहुनैष्किकम् ।

१६९६ । बिस्ताच्च । ५ । १ । ३१ । द्वित्रिबहुपूर्वाद्बिस्तादार्हीयस्य लुग्वा स्यात् । द्विबिस्तम्–द्विबैस्तिकमित्यादि ।

१६९७ । विंशतिकात्खः । ५ । १ । ३२ । अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ।

१६९८ । खार्या ईकन् । ५ । १ । ३३ । अध्यर्धखारीकम् । द्विखारीकम् । 'केवलायाश्चेति वक्तव्यम्' (वा २०२५) । खारीकम् ।

१६९९ । पणपादमाषशताद्यत् । ५ । १ । ३४ । अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह 'पादः पत्' (सू ४१४) इति न । 'यस्य–' (सू ३११) इति लोपस्य स्थानिवद्भावात् । 'पद्यत्यतदर्थे' (सू ९९१) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ।

१७०० । शाणाद्वा । ५ । १ । ३५ । यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम्–अध्यर्धशाणम् ।

१७०१ । द्वित्रिपूर्वादण्च । ५ । १ । ३६ । 'शाणात्' इत्येव । चाद्यत् । तेन त्रैरूप्यम् । 'परिमाणान्तस्यासंज्ञाशाणयोः' (सू १६८३) इति पर्युदासादादिवृद्धिरेव । द्वैशाणम्–द्विशाण्यम्–द्विशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाश्चाकाङ्क्षितास्त इदानीमुच्यन्ते ।

१७०२ । तेन क्रीतम् । ५ । १ । ३७ । ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ।

१७०३ । इद्गोण्याः । १ । २ । ५० । गोण्या इत्स्यात्तद्धितलुकि लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ।

१७०४ । तस्य निमित्तं संयोगोत्पातौ । ५ । १ । ३८ । संयोगः संबन्धः । उत्पातः शुभाशुभसूचकः । शतिकः–शत्यो वा धनपतिसंयोगः । शत्यं–शतिकं दक्षिणाक्षिस्पन्दनं शतस्य निमित्तमित्यर्थः । 'वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम्' (वा ३०३३) । वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् । 'संनिपाताच्चेति वक्तव्यम्' (वा ३०३७) । सांनिपातिकम् ।

१७०५ । गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् । ५ । १ । ३९ । गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचः । धन्यः । यशस्यः । स्वर्ग्यः । 'गोद्व्यचः–' किम् । विजयस्य वैजयिकः । 'असंख्या–' इत्यादि किम् । पञ्चानां पञ्चकम् । साप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि–आश्विकम् । आश्मिकम् । 'ब्रह्मवर्चसादुपसंख्यानम्–' (वा ३०३५) । ब्रह्मवर्चस्यम् ।

१७०६ । पुत्राच्छ च । ५ । १ । ४० । चाद्यत् । पुत्रीयः–पुत्र्यः ।

१७०७ । सर्वभूमिपृथिवीभ्यामणञौ । ५ । १ । ४१ । सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते ।

१७०८ । तस्येश्वरः । ५ । १ । ४२ ।

१७०९ । तत्र विदित इति च । ५ । १ । ४३ । सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ।

१७१० । लोकसर्वलोकाट्ठञ् । ५ । १ । ४४ । 'तत्र विदितः' इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ।

१७११ । तस्य वापः । ५ । १ । ४५ । उप्यतेऽस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ।

१७१२ । पात्रात्ष्ठन् । ५ । १ । ४६ । पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ।

१७१३ । तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते । ५ । १ । ४७ । वृद्धिरित्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिकः-शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा । 'चतुर्थ्यर्थे उपसंख्यानम्' (वा ३०३६)। पञ्च वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । 'सममब्राह्मणे दानम्' इतिवदधिकरणत्वविवक्षा वा।

१७१४ । पूरणार्धाट्ठन् । ५ । १ । ४८ । यथाक्रम ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः । तृतीयिकः । अर्धिकः । अर्धशब्दो रूपकस्यार्थे रूढः।

१७१५ । भागाद्यच । ५ । १ । ४९ । चाट्ठन् । भागशब्दोऽपि रूपकस्यार्थे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते भाग्यं-भागिकं शतम् । भाग्या-भागिका विंशतिः ।

१७१६ । तद्धरति वहत्यावहति भाराद्वंशादिभ्यः । ५ । १ । ५० । वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । 'भाराद्वंशादिभ्यः' इत्यस्य व्याख्यान्तरं 'भारभूतेभ्यो वंशादिभ्यः' इति । भारभूतान्वंशान्हरति वांशिकः । ऐक्षुकः ।

१७१७ । वस्नद्रव्याभ्यां ठन्कनौ । ५ । १ । ५१ । यथासंख्यं स्तः । वस्नं हरति वहत्यावहति वा वस्निकः । द्रव्यकः ।

१७१८ । संभवत्यवहरति पचति । ५ । १ । ५२ । प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः । 'तत्पचतीति द्रोणादण्च' (वा ३०३८) । चाट्ठञ् । द्रोणं पचतीति द्रौणी-द्रौणिकी।

१७१९ । आढकाचितपात्रात्खोऽन्यतरस्याम् । ५ । १ । ५३ । पक्षे ठञ् । आढकं संभवति अवहरति पचति वा आढकीना-आढकिकी । अचितीना-आचितिकी । पात्रीणा-पात्रिकी ।

१७२० । द्विगोः ष्ठंश्च । ५ । १ । ५४ । 'आढकाचितपात्रात्' इत्येव । आढकान्ताद्द्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्य 'अध्यर्ध-' (सू १६९३) इति लुक् । षित्वान्ङीष् । द्व्याढकिकी-द्व्याढकीना । 'द्विगोः' (सू ४७९) इति ङीप् । द्व्याढकी । द्व्याचितिकी-द्व्याचितीना । 'अपरिमाण-' (सू ४८०) इति ङीब्निषेधात् द्व्याचिता । द्विपात्रिकी-द्विपात्रीणा-द्विपात्री ।

१७२१ । कुलिजाल्लुक्खौ च । ५ । १ । ५५ । कुलिजान्ताद्द्विगोः संभवत्यादि

लुक्खौ वा स्तः। चात्ठंञ्च। लुगभावे ठञः श्रवणम्। द्विकुलिर्जी–द्वैकुलिजिकी–द्विकुलिजीना। द्विकुलिजिकी।

१७२२। सोऽस्यांशवस्नभृतयः। ५। १। ५६। अंशो भागः। वस्नं मूल्यम्। भृतिर्वेतनम्। पञ्च अंशो वस्नो भृतिर्वास्य पञ्चकः।

१७२३। तदस्य परिमाणम्। ५। १। ५७। प्रस्थं परिमाणमस्य प्रास्थिको राशिः।

१७२४। संख्यायाः संज्ञासंघसूत्राध्ययनेषु। ५। १। ५८। पूर्वसूत्रमनुवर्तते। तत्र 'संज्ञायां स्वार्थे प्रत्ययो वाच्यः' (वा ३०३९) यद्वा द्व्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः। पञ्चैव पञ्चकाः शकुनयः। पञ्च परिमाणमेषामिति वा। संघे पञ्चकः। सूत्रेऽष्टकं पाणिनीयम्। संघशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृथगुपात्तम्। पञ्चकमध्ययनम्। 'स्तोमे डविधिः' (वा ३०४५)। पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः। सप्तदशः। एकविंशः। सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः।

१७२५। पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्। ५। १। ५९। एते रूढिशब्दा निपात्यन्ते।

१७२६। पञ्चद्दशतौ वर्गे वा। ५। १। ६०। पञ्च परिमाणमस्य पञ्चद्वर्गः। दशत्। पक्षे पञ्चकः। दशकः।

१७२७। त्रिंशच्चत्वारिंशतो ब्राह्मणे संज्ञायां डण्। ५। १। ६२। त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि। चात्वारिंशानि।

१७२८। तदर्हति। ५। १। ६३। लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः।

१७२९। छेदादिभ्यो नित्यम्। ५। १। ६४। नित्यमाभीक्ष्ण्यम्। छेदं नित्यमर्हति छैदिको वेतसः। छित्रमरूढत्वात्। 'विराग विरङ्गं च' (ग सू ९९)। विरागं नित्यमर्हति वैरागिकः–वैरङ्गिकः।

१७३०। शीर्षच्छेदाद्यच्च। ५। १। ६५। शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः– शैर्षच्छेदिकः। यद्वकोः संनियोगेन शिरसः शीर्षभावो निपात्यते।

१७३१। दण्डादिभ्यो यत्। ५। १। ६६। एभ्यो यत्स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः।

१७३२। पात्राद्घंश्च। ५। १। ६८। चाद्यत्तदर्हतीत्यर्थे। पात्रियः–पात्र्यः।

१७३३। कडंकरदक्षिणाच्छ च। ५। १। ६९। चाद्यत्। कडं करोतीति विग्रहेऽत एव निपातनात्खच्। कडंकरं माषमुद्गादिकाष्ठमर्हतीति कडंकरीयो गौः। कडंकर्यः। दक्षिणामर्हतीति दक्षिणीयः–दक्षिण्यः।

१७३४। स्थालीबिलात्। ५। १। ७०। स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः– स्थालीबिल्याः। पाकयोग्या इत्यर्थः।

१७३५। यज्ञर्त्विग्भ्यां घखञौ। ५। १। ७१। यथासंख्यं स्तः। यज्ञमृत्विजं वार्हति यज्ञियः। आर्त्विजीनो यजमानः। 'यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम्' (वा ३०५२)। यज्ञियो देशः। आर्त्विजीन ऋत्विक्।

इति तद्धितार्हीयप्रकरणम्।

अथ तद्धितठञधिकारप्रकरणम् ।

अतःपरं ठञेव ।

१७३६ । पारायणतुरायणचान्द्रायणं वर्तयति । ५ । १ । ७२ । पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः । तं वर्तयति तौरायणिको यजमानः । चान्द्रायणिकः ।

१७३७ । संशयमापन्नः । ५ । १ । ७३ । संशयविषयीभूतोऽर्थः सांशयिकः ।

१७३८ । योजनं गच्छति । ५ । १ । ७४ । यौजनिकः । 'क्रोशशतयोजनशतयोरुपसंख्यानम्' (वा ३०५५)। क्रोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः । 'ततोऽभिगमनमर्हतीति च वक्तव्यम्' (वा ३०५६)। क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ।

१७३९ । पथः ष्कन् । ५ । १ । ७५ । षो ङीषर्थः । पन्थानं गच्छति पथिकः । पथिकी ।

१७४० । पन्थो ण नित्यम् । ५ । १ । ७६ । पन्थानं नित्यं गच्छति । पान्थः-पान्था ।

१७४१ । उत्तरपथेनाहृतं च । ५ । १ । ७७ । उत्तरपथेनाहृतमौत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः । 'आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम्' (वा ३०५७) । वारिपथिकम् ।

१७४२ । कालात् । ५ । १ । ७८ । 'व्युष्टादिभ्योऽण्' (सू १७६१) इत्यतः प्रागधिकारोऽयम् ।

१७४३ । तेन निर्वृत्तम् । ५ । १ । ७९ । अह्ना निर्वृत्तमाह्निकम् ।

१७४४ । तमधीष्टो भृतो भूतो भावी । ५ । १ । ८० । अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतकालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ।

१७४५ । मासाद्वयसि यत्खञौ । ५ । १ । ८१ । मासं भूतो मास्यः-मासीनः ।

१७४६ । द्विगोर्यप् । ५ । १ । ८२ । मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ।

१७४७ । षण्मासाण्ण्यच्च । ५ । १ । ८३ । 'वयसि' इत्येव । यबप्यनुवर्तते । चाट्ठञ् । षण्मास्यः-षाण्मास्यः-षाण्मासिकः ।

१७४८ । अवयसि ठंश्च । ५ । १ । ८४ । चाण्ण्यत् । षाण्मासिको व्याधिः-षाण्मास्यः ।

१७४९ । समायाः खः । ५ । १ । ८५ । समामधीष्टो भृतो भूतो भावी वा समीनः ।

१७५० । द्विगोर्वा । ५ । १ । ८६ । 'समायाः खः' इत्येव । 'तेन परिजय्य-' (सू १७ इत्यतः प्राङ्निर्वृत्तादिषु पञ्चस्वर्थेषु प्रत्ययाः । द्विसमीनः-द्वैसमिकः ।

१७५१ । रात्र्यहःसंवत्सराच्च । ५ । १ । ८७ । 'द्विगोः' इत्येव । द्विरात्रीणः-द्वैरात्रिकः । द्व्यहीनः-द्वैयह्निकः । समासान्तविधेरनित्यत्वान्न टच् । द्विसंवत्सरीणः ।

१७५२ । संख्यायाः संवत्सरसंख्यस्य च । ७ । ३ । १५ । संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । 'संख्यायाः परिमाणान्तस्य' इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ।

१७५३। वर्षाल्लुक्च। ५। १। ८८। वर्षशब्दान्ताद्द्विगोर्वा खः। पक्षे ठञ्चा च लुक्। त्रीणि रूपाणि। द्विवर्षीणो व्याधिः। द्विवार्षिकः–द्विवर्षः।

१७५४। वर्षस्याभविष्यति। ७। ३। १६। उत्तरपदस्य वृद्धिः स्यात्। द्विवार्षिकः। भविष्यति तु द्वैवर्षिकः। अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न। गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः। द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः। 'परिमाणान्तस्यासंज्ञाशाणयोः' (सू. १६८३)। द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः। द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम्। द्विनैष्किकम्। 'असंज्ञा–' इति किम्। पञ्च कपालाः परिमाणमस्य पाञ्चकपालिकम्। तद्धितान्तः संज्ञा। द्वैशाणम्। कुलिजशब्दमपि केचित्पठन्ति। द्वैकुलिजिकः।

१७५५। चित्तवति नित्यम्। ५। १। ८९। वर्षशब्दान्ताद्द्विगोः प्रत्ययस्य नित्यं लुक्स्याचेतने प्रत्ययार्थे। द्विवर्षो दारकः।

१७५६। षष्टिकाः षष्टिरात्रेण पच्यन्ते। ५। १। ९०। बहुवचनमतन्त्रम्। षाष्टिको धान्यविशेषः। तृतीयान्तात्कन्रात्रशब्दलोपश्च निपात्यते।

१७५७। तेन परिजय्यलभ्यकार्यसुकरम्। ५। १। ९३। मासेन परिजय्यो जेतुं शक्यो मासिको व्याधिः। मासेन लभ्यं कार्यं सुकरं वा मासिकम्।

१७५८। तदस्य ब्रह्मचर्यम्। ५। १। ९४। द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात्। अत्यन्तसंयोगे द्वितीया। मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी। आर्धमासिकः। यद्वा। प्रथमान्तादस्येत्यर्थे प्रत्ययः। मासोऽस्येति मासिकं ब्रह्मचर्यम्। 'महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम्' (वा ३०६४)। महानाम्न्यो नाम 'विदा मघवन्–'इत्याद्या ऋचः। तासां ब्रह्मचर्यमस्य माहानाम्निकः। हरदत्तस्तु 'भस्याढे–' इति पुंवद्भावान्माहानामिक इत्याह। 'चतुर्मासाण्ण्यो यज्ञे तत्र भव इत्यर्थे' (वा ३०६९)। चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि। 'संज्ञायामण्' (वा ३०७०) चतुर्षु मासेषु भवति चातुर्मासी। पौर्णमासी। अण्णन्तत्वान्ङीप्।

१७५९। तस्य दक्षिणा यज्ञाख्येभ्यः। ५। १। ९५। द्वादशाहस्य दक्षिणा द्वादशाहिकी। आख्याग्रहणादकालादपि। आग्निष्टोमिकी। वाजपेयिकी।

१७६०। तत्र च दीयते कार्यं भववत्। ५। १। ९६। प्रावृषि दीयते कार्यं वा प्रावृषेण्यम्। शारदम्।

इति कालिकप्रकरणम्।

१७६१। व्युष्टादिभ्योऽण्। ५। १। ९७। व्युष्टे दीयते कार्यं वा वैयुष्टम्। व्युष्ट तीर्थ संग्राम प्रवास इत्यादि। ['अग्निपदादिभ्य उपसंख्यानम्' (वा ३०७२)। अग्निपदे दीयते कार्यं वाग्निपदम्। पैलुमूलम्।]

१७६२। तेन यथाकथाचहस्ताभ्यां णयतौ। ५। १। ९८। यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च यथासंख्यं णयतौ स्तः। 'अर्थाभ्यां तु यथासंख्यं नेष्यते' यथाकथाच दीयते कार्यं वा याथाकथाचम्। अनादरेण देयं कार्यं वेत्यर्थः। हस्तेन दीयते कार्यं वा हस्त्यम्।

१७६३ । संपादिनि । ५ । १ । ९९ । 'तेन' इत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवे... किकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभत इत्यर्थः ।

१७६४ । कर्मवेषाद्यत् । ५ । १ । १०० । कर्मणा संपादि कर्मण्यं शौर्यम् । वे... संपादि वेष्यो नटः । वेषः कृत्रिम आकारः ।

१७६५ । तस्मै प्रभवति संतापादिभ्यः । ५ । १ । १०१ । संतापाय प्रभवति सांतापि... सांग्रामिकः ।

१७६६ । योगाद्यच्च । ५ । १ । १०२ । चाट्ठञ् । योगाय प्रभवति योग्यः—यौगिकः ।

१७६७ । कर्मण उकञ् । ५ । १ । १०३ । कर्मणे प्रभवति कार्मुकम् ।

१७६८ । समयस्तदस्य प्राप्तम् । ५ । १ । १०४ । समयः प्राप्तोऽस्य सामयिकम् ।

१७६९ । ऋतोरण् । ५ । १ । १०५ । ऋतुः प्राप्तोऽस्य आर्तवम् । ['उपवस्त्रादिभ्य उ... संख्यानम्' । उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ।]

१७७० । कालाद्यत् । ५ । १ । १०७ । कालः प्राप्तोऽस्य काल्यं शीतम् ।

१७७१ । प्रकृष्टे ठञ् । ५ । १ । १०८ । 'कालात्' इत्येव । तदस्येति च । प्रकृष्टो दी... कालोऽस्येति कालिकं वैरम् ।

१७७२ । प्रयोजनम् । ५ । १ । १०९ । 'तदस्य' इत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्... हिकम् । प्रयोजनं फलं कारणं च ।

१७७३ । विशाखाषाढादण्मन्थदण्डयोः । ५ । १ । ११० । आभ्यामण्स्यात्प्रयोजन... त्यर्थे क्रमान्मन्थदण्डयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्... 'चूडादिभ्य उपसंख्यानम्'[२] । चूडा—चौडम् । श्रद्धा—श्राद्धम् ।

१७७४ । अनुप्रवचनादिभ्यश्छः । ५ । १ । १११ । अनुप्रवचनं प्रयोजनमस्य अनु... वचनीयम् ।

१७७५ । समापनात्सपूर्वपदात् । ५ । १ । ११२ । व्याकरणसमापनं प्रयोजनम... व्याकरणसमापनीयम् ।

१७७६ । ऐकागारिकट् चौरे । ५ । १ । ११३ । एकमसहायमगारं प्रयोजनमस्य मु... षिषोः स ऐकागारिकश्चौरः ।

१७७७ । आकालिकडाद्यन्तवचने । ५ । १ । ११४ । समानकालावाद्यन्तौ यस्य... कालिकः । समानकालस्याकाल आदेशः । आशु विनाशीत्यर्थः । पूर्वेद्युर्दिने मध्याह्न... त्पद्य दिनान्तरे तत्रैव नश्वर इति वा । 'आकालाट्ठंश्च (वा २०७८) । आकालिका विद्यु...

इति तद्धितठञधिकारप्रकरणम् ।

अथ तद्धितनञ्स्नञधिकारप्रकरणम् ।

१७७८ । तेन तुल्यं क्रिया चेद्वतिः । ५ । १ । ११५ । ब्राह्मणेन तुल्यं ब्राह्मणवदधी... 'क्रिया चेत्' इति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ।

---

१. ५ । १ । ९७ सूत्रे भाष्ये तु अग्निपदादित्वमेवाश्रितम् । २. ५ । १ । ९१ सूत्रे भाष्ये 'अग्निपदादित्वमेवाश्रितम्' ।

१७७९ । तत्र तस्येव । ५ । १ । ११६ । मथुरायामिव मथुरावत्स्रुघ्ने प्राकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ।

१७८० । तदर्हम् । ५ । १ । ११७ । विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते । तेनेह न । राजानमर्हति छत्रम् ।

१७८१ । तस्य भावस्त्वतलौ । ५ । १ । ११९ । प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । 'त्वान्तं क्लीबम्' (लि १२०) । 'तलन्तं स्त्रियाम्' (लि १७) ।

१७८२ । आ च त्वात् । ५ । १ । १२० । ब्रह्मणस्त्व इत्यतः प्राक्त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थम् । गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रिया भावः स्त्रैणम्—स्त्रीत्वम्—स्त्रीता । पौंस्नम्—पुंस्त्वम्—पुंस्ता ।

१७८३ । न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः । ५ । १ । १२१ । इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । 'नञ्पूर्वात्' किम् । बार्हस्पत्यम् । 'तत्पुरुषात्' किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भाव आपटवम् । 'अचतुर—' इति किम् । आचतुर्यम् । आसंगत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ।

१७८४ । पृथ्वादिभ्य इमनिज्वा । ५ । १ । १२२ । वावचनमणादिसमावेशार्थम् ।

१७८५ । र ऋतो हलादेर्लघोः । ६ । ४ । १६१ । हलादेर्लघोर्ऋकारस्य रः स्यात् इष्टेमेयस्सु ।

१७८६ । टेः । ६ । ४ । १५५ । भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा—पार्थवम् । म्रदिमा—मार्दवम् ।

१७८७ । वर्णदृढादिभ्यः ष्यञ्च । ५ । १ । १२३ । चादिमनिच । शौक्ल्यम्—शुक्लिमा । दार्ढ्यम् । 'पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम्' (वा ४२११) । द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ।

१७८८ । गुणवचनब्राह्मणादिभ्यः कर्मणि च । ५ । १ । १२४ । चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् । 'अर्हतो नुम्च—' (वा ३०९२) । अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ।

१७८९ । यथातथयथापुरयोः पर्यायेण । ७ । ३ । ३१ । नञः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम्—अयाथातथ्यम् । आयथापुर्यम् । अयथापुर्यम् । आपादसमाप्तेर्भावकर्माधिकारः । 'चतुर्वर्णादीनां स्वार्थ उपसंख्यानम्' (वा ३०९१) । चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाड्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः । 'सर्वादेः—' (वा २७४८) इति लुक् । स एव सार्ववैद्यः । 'चतुर्वेदस्योभयपदवृद्धिश्च' (ग सू ९३) । चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । 'चतुर्विद्यस्य' इति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ।

१७९० । स्तेनाद्यन्नलोपश्च । ५ । १ । १२५ । 'न' इति संघातग्रहणम् । 'स्तेन चौर्ये'

पचाद्यत् । स्तेनस्य भावः कर्म वा स्तेयम् । 'स्तेनात्' इति योगं विभज्य स्तैन्यमिति ण्य-न्तमपि केचिदिच्छन्ति ।

१७९१ । सख्युर्यः । ५ । १ । १२६ । सख्युर्भावः कर्म वा सख्यम् 'दूतवणिग्भ्यां च' दूतस्य भावः कर्म वा दूत्यम् । 'वणिज्यम्–' इति काशिका । माधवस्तु 'वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः । भाव एव चात्र प्रत्ययो न तु कर्मणि' इत्याह । भाष्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ।

१७९२ । कपिज्ञात्योर्ढक् । ५ । १ । १२७ । कापेयम् । ज्ञातेयम् ।

१७९३ । पत्यन्तपुरोहितादिभ्यो यक् । ५ । १ । १२८ । सैनापत्यम् । पौरोहित्यम् । 'राजासे' (ग सू० १०६) । राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात्ष्यञ् । आधिराज्यम् ।

१७९४ । प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् । ५ । १ । १२९ । प्राणभृज्जातिः आश्वम् । औष्ट्रम् । वयोवचनम् । कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ।

१७९५ । हायनान्तयुवादिभ्योऽण् । ५ । १ । १३० । द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् । 'श्रोत्रियस्य घलोपश्च' (वा ३०९३) । श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ।

१७९६ । इगन्ताच्च लघुपूर्वात् । ५ । १ । १३१ । शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्ष्यञ् ।

१७९७ । योपधाद्गुरूपोत्तमाद्वुञ् । ५ । १ । १३२ । रामणीयकम् । आभिधानीयकम् । 'सहायाद्वा' (वा० २०९४) । साहाय्यम् । साहायकम् ।

१७९८ । द्वन्द्वमनोज्ञादिभ्यश्च । ५ । १ । १३३ । शैष्योपाध्यायिका । मानोज्ञकम् ।

१७९९ । गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु । ५ । १ । १३४ । अत्याकारोऽधिक्षेपः । तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयात्याकुरुते । गार्गिकामवेतः ।

१८०० । होत्राभ्यश्छः । ५ । १ । १३५ । होत्राशब्दो ऋत्विग्वाची स्त्रीलिङ्गः । बहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा अच्छावाकीयम् । मैत्रावरुणीयम् ।

१८०१ । ब्रह्मणस्त्वः । ५ । १ । १३६ । होत्रावाचिनो ब्रह्मशब्दात्त्वः स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेतिवाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात् त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ।

इति तद्धितनञ्स्नञधिकारप्रकरणम् ।

अथ तद्धितमत्वर्थीयप्रकरणम् ।

१८०२ । धान्यानां भवने क्षेत्रे खञ् । ५ । २ । १ । भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ।

१८०३ । व्रीहिशाल्योर्ढक् । ५ । २ । २ । व्रैहेयम् । शालेयम् ।

१८०४ । यवयवकषष्टिकाद्यत् । ५ । २ । ३ । यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ।

१८०५ । विभाषा तिलमाषोमाभङ्गाणुभ्यः । ५ । २ । ४ । यद्वा स्यात् । पक्षे खञ् । तिल्यम्–तैलीनम् । माष्यम्–माषीणम् । उम्यम्–औमीनम् । भङ्ग्यम्–भाङ्गीनम् । अणव्यम्–आणवीनम् ।

१८०६ । सर्वचर्मणः कृतः खखञौ । ५ । २ । ५ ।असामर्थ्येऽपि निपातनात्समासः। सर्वश्चर्मणा कृतः सर्वचर्मीणः–सार्वचर्मीणः ।

१८०७ । यथामुखसंमुखस्य दर्शनः खः । ५ । २ । ६ । मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ।

१८०८ । तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । ५ । २ । ७ । सर्वादेः पथ्याद्यन्ताद्द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः ।

१८०९ । आप्रपदं प्राप्नोति । ५ । २ । ८ । पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ।

१८१० । अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । ५ । २ । ९ । अनुरायामे सादृश्ये वा । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः । तं नेयोऽयानयीनः शारः ।

१८११ । परोवरपरंपरपुत्रपौत्रमनुभवति । ५ । २ । १० । परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्त्वं निपात्यते । परांश्च परतरांश्चानुभवति परंपरीणः । प्रकृतेः परंपरभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेव । खप्रत्ययसंनियोगेनैव परोवरेति निपातनात् ।

१८१२ । अवारपारात्यन्तानुकामं गामी । ५ । २ । ११ । अवारपारं गामी अवारपारीणः–अवारीणः–पारीणः–पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्ता ।

१८१३ । समांसमां विजायते । ५ । २ । १२ । यलोपोऽवशिष्टविभक्तेरलुक्च पूर्वपदे निपात्यते । समांसमीना गौः । 'समांसमीना सा यैव प्रतिवर्षं प्रसूयते' इत्यमरः । 'खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः' (वा ३१००) । समां समां विजायते । समायां समायां वा ।

१८१४ । अद्यश्वीनावष्टब्धे । ५ । २ । १३ । अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ।

१८१५ । आगवीनः । ५ । २ । १४ । आङ्पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ।

१८१६। अनुग्वलंगामी। ५। २। १५। अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवी गोपालः।

१८१७। अध्वनो यत्खौ। ५। २। १६। अध्वानमलं गच्छति अध्वन्यः-अध्वनीनः। 'ये चाभावकर्मणोः' (सू ११५४), 'आत्माध्वानौ खे' (सू १६७१) इति सूत्राभ्यां प्रकृतिभावः।

१८१८। अभ्यमित्राच्छ च। ५। २। १७। चाद्यत्खौ। अभ्यमित्रीयः-अभ्यमित्र्यः-अभ्यमित्रीणः। अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः।

१८१९। गोष्ठात्खञ्भूतपूर्वे। ५। २। १८। गोष्ठो भूतपूर्वः गौष्ठीनो देशः।

१८२०। अश्वस्यैकाहगमः। ५। २। १९। एकाहेन गम्यत इत्येकाहगम आश्वीनोऽध्वा।

१८२१। शालीनकौपीने अधृष्टाकार्ययोः। ५। २। २०। शालाप्रवेशमर्हति शालीनोऽधृष्टः। कूपपतनमर्हति कौपीनं पापम्। तत्साधनत्वात्तद्गोप्यत्वात्पुरुषलिङ्गमपि। तत्सम्बन्धात्तदाच्छादनमपि।

१८२२। व्रातेन जीवति। ५। २। २१। व्रातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स व्रातीनः।

१८२३। साप्तपदीनं सख्यम्। ५। २। २२। सप्तभिः पदैरवाप्यते साप्तपदीनम्।

१८२४। हैयङ्गवीनं संज्ञायाम्। ५। २। २३। ह्योगोदोहस्य हियङ्गुरादेशो विकारे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम्।

१८२५। तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ। ५। २। २४। पीलूनां पाकः पीलुकुणः। कर्णस्य मूलं कर्णजाहम्।

१८२६। पक्षात्तिः। ५। २। २५। मूलग्रहणमात्रमनुवर्तते। पक्षस्य मूलं पक्षतिः।

१८२७। तेन वित्तश्चुञ्चुप्चणपौ। ५। २। २६। यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा। विद्यया वित्तो विद्याचुञ्चुः। विद्याचणः।

१८२८। विनञ्भ्यां नानाञौ न सह। ५। २। २७। असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ। विना। नाना।

१८२९। वेः शालच्छङ्कटचौ। ५। २। २८। क्रियाविशिष्टसाधनवाचकात्स्वार्थे। विस्तृतम्। विशालम्। विशङ्कटम्।

१८३०। संप्रोदश्च कटच्। ५। २। २९। संकटम्। प्रकटम्। उत्कटम्। 'अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्' (वा ३१०७)। अलाबूनां रजः अलाबूकटम्। 'गोष्ठजादयः स्थानादिषु पशुनामभ्यः' (वा ३१०९)। गवां स्थानं गोगोष्ठम्। 'संघाते कटच्' (वा ३११०)। अवीनां संघातोऽविकटः। 'विस्तारे पटच्' (वा ३१११)। अविपटः। 'द्वित्वे गोयुगच्'। (वा ३११६)। द्वावुष्ट्रौ उष्ट्रगोयुगम्। 'षड्त्वे षड्गवच्' (वा ३११७) अश्वषड्गवम्। 'स्नेहे तैलच्' (वा ३११८)। तिलतैलम्। सर्षपतैलम्। 'भवने क्षेत्रे शाकटशाकिनौ' (वा ३११९)। इक्षुशाकटम्। इक्षुशाकिनम्।

१८३१। अवात्कुटारच्च। ५। २। ३०। चात्कटच्। अवाचीनोऽवकुटारः। अवकटः।

१८३२। नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः। ५। २। ३१। 'अ...

---

१. उकारद्वयवान्-इति मनोरमा।

इत्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनाटम् । अवभ्रटम् । तद्योगान्नासिकावटीटा । पुरुषोऽप्यवटीटः ।

१८३३ । नेर्बिडज्बिरीसचौ । ५ । २ । ३२ । निबिडम् । निबिरीसम् ।

१८३४ । इनच्पिटच्चिकचि च । ५ । २ । ३३ । 'नेः' इत्येव । नासिकाया नतेऽभिधेये इनच्पिटचौ प्रत्ययौ प्रकृतेश्चिकचीत्यादेशौ च । 'कप्रत्ययचिकादेशौ च वक्तव्यौ' (वा ३१२१) । चिक्किनम् । चिपिटम् । चिक्कम् । 'क्लिन्नस्य चिल्पिल्लश्चास्य चक्षुषी' (वा ३१२२) । क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः । 'चुल् च' (वा ३१२३) । चुल्लः ।

१८३५ । उपाधिभ्यां त्यकन्नासन्नारूढयोः । ५ । २ । ३४ । 'संज्ञायाम्' इत्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ।

१८३६ । कर्मणि घटोऽठच् । ५ । २ । ३५ । घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ।

१८३७ । तदस्य संजातं तारकादिभ्य इतच् । ५ । २ । ३६ । तारकाः संजाता अस्य तारकितं नभः । आकृतिगणोऽयम् ।

१८३८ । प्रमाणे द्वयसज्दघ्नञ्मात्रचः । ५ । २ । ३७ । 'तदस्य' इत्यनुवर्तते । ऊरु प्रमाणमस्य ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम् । 'प्रमाणे लः' (वा ३१२८) । शमः दिष्टिः । वितस्तिः । 'द्विगोर्नित्यम्' (वा ३१२९) । द्वौ शमौ प्रमाणमस्य द्विशमम् । 'प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः' (वा ३१३३) । शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् । 'वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम्' (वा ३१३४) । तावदेव तावद्द्वयसम् । तावन्मात्रम् ।

१८३९ । पुरुषहस्तिभ्यामण्च । ५ । २ । ३८ । पुरुषः प्रमाणमस्य पौरुषम्–पुरुषद्वयसम् । हास्तिनम्–हस्तिद्वयसम् ।

१८४० । यत्तदेतेभ्यः परिमाणे वतुप् । ५ । २ । ३९ । यत्परिमाणमस्य यावान् । तावान् । एतावान् ।

१८४१ । किमिदंभ्यां वो घः । ५ । २ । ४० । आभ्यां वतुप्स्याद्वस्य च घः । कियान् । इयान् ।

१८४२ । किमः संख्यापरिमाणे डति च । ५ । २ । ४१ । चाद्वतुप् । तस्य च वस्य घः स्यात् । काः संख्या येषां ते कति–कियन्तः ।

१८४३ । संख्याया अवयवे तयप् । ५ । २ । ४२ । पञ्चावयवा अस्य पञ्चतयं दारु ।

१८४४ । द्वित्रिभ्यां तयस्यायज्वा । ५ । २ । ४३ । द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ।

१८४५ । उभादुदात्तो नित्यम् । ५ । २ । ४४ । उभशब्दात्तयपोऽयच्स्यादाद्युदात्तः । उभयम् ।

१८४६ । तदस्मिन्नधिकमिति दशान्ताड्डः । ५ । २ । ४५ । एकादशाधिका अस्मिन्नेकादशम् । 'शतसहस्रयोरेवेष्यते' (वा ३१४१) । नेह । एकादशाधिका अस्यां विंशतौ ।

'प्रकृतिप्रत्ययार्थयोः समानजातीयत्वमेवेष्यते' (वा ३१४०)। नेह । एकादश माषा अधि-
अस्मिन्सुवर्णशते ।

१८४७ । शदन्तविंशतेश्च । ५ । २ । ४६ । डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन्
शतम् । विंशम् ।

१८४८ । संख्याया गुणस्य निमाने मयट् । ५ । २ । ४७ । भागस्य मूल्ये वर्तमान-
त्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भाग-
स्य द्विमयमुदश्विद्यवानाम् । 'गुणस्य' इति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वित
'निमाने' किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ।

१८४९ । तस्य पूरणे डट् । ५ । २ । ४८ । एकादशानां पूरण एकादशः ।

१८५० । नान्तादसंख्यादेर्मट् । ५ । २ । ४९ । डटो मडागमः स्यात् । पञ्चानां पूर-
पञ्चमः । 'नान्तात्' किम् । विंशः । 'असंख्यादेः' किम् । एकादशः ।

१८५१ । षट्कतिकतिपयचतुरां थुक् । ५ । २ । ५१ । एषां थुगागमः स्याड्डटि । षण्
पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट् । कतिपयथः
चतुर्थः । 'चतुरश्छयतावाद्यक्षरलोपश्च' (वा ३१५८) । तुरीयः–तुर्यः ।

१८५२ । बहुपूगगणसंघस्य तिथुक् । ५ । २ । ५२ । 'डटि' इत्येव । पूगसंघयोरसं-
ख्यात्वेऽप्यत एव डट् । बहुतिथः इत्यादि ।

१८५३ । वतोरिथुक् । ५ । २ । ५३ । 'डटि' इत्येव । यावतिथः ।

१८५४ । द्वेस्तीयः । ५ । २ । ५४ । डटोऽपवादः । द्वयोः पूरणो द्वितीयः ।

१८५५ । त्रेः संप्रसारणं च । ५ । २ । ५५ । तृतीयः ।

१८५६ । विंशत्यादिभ्यस्तमडन्यतरस्याम् । ५ । २ । ५६ । एभ्यो डटस्तमडागमो
वा स्यात् । विंशतितमः–विंशः । एकविंशतितमः–एकविंशः ।

१८५७ । नित्यं शतादिमासार्धमाससंवत्सराच्च । ५ । २ । ५७ । शतस्य पूरणः
शततमः । एकशततमः । मासादेरत एव डट् । मासतमः ।

१८५८ । षष्ट्यादेश्चासंख्यादेः । ५ । २ । ५८ । षष्टितमः । संख्यादेस्तु विंशत्यादि-
(सू १८५६) इति विकल्प एव । एकषष्टः–एकषष्टितमः ।

१८५९ । मतौ छः सूक्तसाम्नोः । ५ । २ । ५९ । मत्वर्थे छः स्यात् । अच्छावाकशब्दो-
ऽस्मिन्नस्ति अच्छावाकीयं सूक्तम् । वारवन्तीयं साम ।

१८६० । अध्यायानुवाकयोर्लुक् । ५ । २ । ६० । मत्वर्थस्य छस्य । अत एव ज्ञापका-
न्न छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः–गर्दभाण्डीयः ।

१८६१ । विमुक्तादिभ्योऽण् । ५ । २ । ६१ । मत्वर्थेऽण्स्यादध्यायानुवाकयोः । वि-
मुक्तशब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ।

१८६२ । गोषदादिभ्यो वुन् । ५ । २ । ६२ । मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्व-

१८६३ । तत्र कुशलः पथः । ५ । २ । ६३ । वुन्स्यात् । पथि कुशलः पथिकः ।

१८६४ । आकर्षादिभ्यः कन् । ५ । २ । ६४ । आकर्षे कुशल आकर्षकः । 'आक-
दिभ्यः' इति रेफरहितो मुख्यः पाठः । आकषो निकषः ।

१८६५ । धनहिरण्यात्कामे । ५ । २ । ६५ । काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ।

१८६६ । स्वाङ्गेभ्यः प्रसिते । ५ । २ । ६६ । केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ।

१८६७ । उदराट्ठगाद्यूने । ५ । २ । ६७ । अविजिगीषौ ठक्स्यात्कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । 'आद्यूने' किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ।

१८६८ । सस्येन परिजातः । ५ । २ । ६८ । कन्स्मर्यते न तु ठक् । सस्यशब्दो गुणवाची न तु धान्यवाची । 'शस्येन' इति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ।

१८६९ । अंशं हारी । ५ । २ । ६९ । 'हारी' इत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ।

१८७० । तन्त्रादचिरापहृते । ५ । २ । ७० । तन्त्रकः पटः । प्रत्यग्र इत्यर्थः ।

१८७१ । ब्राह्मणकोष्णिके संज्ञायाम् । ५ । २ । ७१ । आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्योष्णादेशो निपात्यते ।

१८७२ । शीतोष्णाभ्यां कारिणि । ५ । २ । ७२ । शीतं करोतीति शीतकोऽलसः । उष्णं करोतीत्युष्णकः शीघ्रकारी ।

१८७३ । अधिकम् । ५ । २ । ७३ । अध्यारूढशब्दात्कनुत्तरपदलोपश्च ।

१८७४ । अनुकाभिकाभीकः कमिता । ५ । २ । ७४ । अन्वभिभ्यां कन्नभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । अभिकामयतेऽभिकः—अभीकः ।

१८७५ । पार्श्वेनान्विच्छति । ५ । २ । ७५ । अनृजुरुपायः पार्श्वं, तेनान्विच्छति पार्श्वकः ।

१८७६ । अयःशूलदण्डाजिनाभ्यां ठक्ठञौ । ५ । २ । ७६ । तीक्ष्ण उपायोऽयःशूलं, तेनान्विच्छति आयःशूलिकः । साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः ।

१८७७ । तावतिथं ग्रहणमिति लुग्वा । ५ । २ । ७७ । कन्स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं—द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः । 'तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक्' (वा ३१७२) । षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ।

१८७८ । स एषां ग्रामणीः । ५ । २ । ७८ । देवदत्तो मुख्योऽस्य देवदत्तकः । त्वत्कः । मत्कः ।

१८७९ । शृङ्खलमस्य बन्धनं करभे । ५ । २ । ७९ । शृङ्खलकः करभः ।

१८८० । उत्क उन्मनाः । ५ । २ । ८० । उद्गतमनस्कवृत्तेरुच्छब्दात्स्वार्थे कन् । उत्क उत्कण्ठितः ।

१८८१ । कालप्रयोजनाद्रोगे । ५ । २ । ८१ । कालवचनात्प्रयोजनवचनाच्च कन्स्या-

द्रागे। द्वितीयेऽहानि भवो द्वितीयको ज्वरः। प्रयोजनं कारणं रोगस्य फलं वा। विषपुष्पैर्जनि
तो विषपुष्पकः। उष्णं कार्यमस्य उष्णकः। 'रोगे' किम्। द्वितीयो दिवसोऽस्य।

१८८२। तदस्मिन्नन्नं प्रायेण संज्ञायाम्। ५। २। ८२। प्रथमान्तात्सप्तम्यर्थे कन् स्यात्
यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत्। गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी।
'वटकेभ्य इनिर्वाच्यः' (वा ३१७५)। वटकिनी।

१८८३। कुल्माषादञ्। ५। २। ८३। कुल्माषाः प्रायेणान्नमस्यां कौल्माषी।

१८८४। श्रोत्रियंश्छन्दोऽधीते। ५। २। ८४। श्रोत्रियः। 'वा' इत्यनुवृत्तेश्छान्दसः।

१८८५। श्राद्धमनेन भुक्तमिनिठनौ। ५। २। ८५। श्राद्धी–श्राद्धिकः।

१८८६। पूर्वादिनिः। ५। २। ८६। पूर्वं कृतमनेन पूर्वी।

१८८७। सपूर्वाच्च। ५। २। ८७। कृतपूर्वी।

१८८८। इष्टादिभ्यश्च। ५। २। ८८। इष्टमनेन इष्टी। अधीती।

१८८९। छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि। ५। २। ८९। लोके तु परि
पन्थिशब्दो न न्याय्यः।

१८९०। अनुपद्यन्वेष्टा। ५। २। ९०। अनुपदमन्वेष्टा गवामनुपदी।

१८९१। साक्षाद्द्रष्टरि संज्ञायाम्। ५। २। ९१। साक्षाद्द्रष्टा साक्षी।

१८९२। क्षेत्रियच्परक्षेत्रे चिकित्स्यः। ५। २। ९२। क्षेत्रियो व्याधिः। शरीरा
न्तरे। चिकित्स्यः। अप्रतिकार्य इत्यर्थः।

१८९३। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। ५।
२। ९३। इन्द्र आत्मा, तस्य लिङ्गं करणेन कर्तुरनुमानात्। इतिशब्दः प्रकारार्थः। इन्द्रेण
दुर्जयमिन्द्रियम्।

१८९४। तदस्यास्त्यस्मिन्निति मतुप्। ५। २। ९४। गावोऽस्यास्मिन्वा सन्ति गोमान्।

'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः॥' (वा ३१८३)

१८९५। रसादिभ्यश्च। ५। २। ९५। मतुप्। रसवान्। रूपवान्। अन्यमत्वर्थीयनि
वृत्त्यर्थं वचनम्। रस। रूप। वर्ण। गन्ध। स्पर्श। शब्द। स्नेह। भाव। 'गुणात्' (ग सू ११२)।
'एकाचः' (ग सू ११३)। स्ववान्। गुणग्रहणं रसादीनां विशेषणम्।

१८९६। तसौ मत्वर्थे। १। ४। १९। तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये।
'वसोः संप्रसारणम्' (सू ४३५)। विदुष्मान्। 'गुणवचनेभ्यो मतुपो लुगिष्टः' (वा ३१८
शुक्लो गुणोऽस्यास्तीति शुक्लः पटः। कृष्णः।

१८९७। मादुपधायाश्च मतोर्वोऽयवादिभ्यः। ८। २। ९। मवर्णावर्णान्तान्मवर्णाव
पधाच्च यवादिवर्जात्परस्य मतोर्मस्य वः स्यात्। किंवान्। ज्ञानवान्। विद्यावान्। लक्ष्मीवान्।
यशस्वान्। भास्वान्। यवादेस्तु यवमान्। भूमिमान्।

१८९८। झयः। ८। २। १०। झयन्तान्मतोर्मस्य वः स्यात्। अपदान्तत्वान्न जश्त्वम्।
विद्युत्वान्।

१८९९। संज्ञायाम्।८।२।११। मतोर्मस्य वः स्यात्। अहीवती। मुनीवती। 'शरादीनां च' (सू १०४२) इति दीर्घः।

१९००। आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती।८।२।१२। एते षट् संज्ञायां निपात्यन्ते। आसनशब्दस्यासन्दीभावः। आसन्दीवान्ग्रामः। अन्यत्रासनवान्। अस्थिशब्दस्याष्ठीभावः। अष्ठीवान्। अस्थिमानन्यत्र। चक्रशब्दस्य चक्रीभावः। चक्रीवा-न्नाम राजा। चक्रवानन्यत्र। कक्ष्यायाः संप्रसारणम्। कक्षीवान्नामर्षिः। कक्ष्यावानन्यत्र। लवणशब्दस्य रुमण्भावः। रुमण्वान्नाम पर्वतः। लवणवानन्यत्र। चर्मणो नलोपाभावो णत्वं च। चर्मण्वती नाम नदी। चर्मवत्यन्यत्र।

१९०१। उदन्वानुदधौ च।८।२।१३। उदकस्योदन्भावो मतावुदधौ संज्ञायां च। उदन्वान्समुद्र ऋषिश्च।

१९०२। राजन्वान्सौराज्ये।८।२।१४। राजन्वती भूः। राजवानन्यत्र।

१९०३। प्राणिस्थादातो लजन्यतरस्याम्।५।२।९६। चूडालः—चूडावान्। 'प्राणि-स्थात्' किम्। शिखावान्दीपः। 'आतः' किम्। हस्तवान्। 'प्राण्यङ्गादेव' (वा ३१८९)। नेह। मेधावान्। प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ 'स्वरितो वानुदात्ते पदादौ' (सू ३६५९) इति स्वरितबाधनार्थश्चकारः।

१९०४। सिध्मादिभ्यश्च।५।२।९७। लच्चा स्यात्। सिध्मलः—सिध्मवान्। अन्य-तरस्यां ग्रहणं मतुप्समुच्चयार्थं न तु प्रत्ययविकल्पार्थम्। तेनाकारान्तेभ्य इनिठनौ न। 'वात-दन्तबलललाटगलानामूङ् च' (ग सू ११९)। वातूलः।

१९०५। वत्सांसाभ्यां कामबले।५।२।९८। आभ्यां लच्चा स्याद्यथासंख्यं काम-वति बलवति चार्थे। वत्सलः। अंसलः।

१९०६। फेनादिलच्च।५।२।९९। चाल्लच्। अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थम-नुवर्तते। फेनिलः—फेनलः—फेनवान्।

१९०७। लोमादिपामादिपिच्छादिभ्यः शनेलचः।५।२।१००। लोमादिभ्यः शः। लोमशः—लोमवान्। रोमशः—रोमवान्। 'पामादिभ्यो नः'। पामनः। 'अङ्गात्कल्याणे' (ग सू ११८)। अङ्गना। 'लक्ष्म्या अच्च' (ग सू १२१)। लक्ष्मणः। 'विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः' (वा ३१९४)। विषुणः। 'पिच्छादिभ्य इलच्'। पिच्छिलः—पिच्छवान्। उरसिलः—उरस्वान्।

१९०८। प्रज्ञाश्रद्धार्चाभ्यो णः।५।२।१०१। प्राज्ञो व्याकरणम्। प्राज्ञा। श्राद्धः। आर्चः। 'वृत्तेश्च' (वा ३१९५)। वार्तः।

१९०९। तपःसहस्राभ्यां विनीनी।५।२।१०२। विनीन्योरिकारो नकारपरित्रा-णार्थः। तपस्वी। सहस्री। असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा मा भूदिति। सहस्रात्तु ठनोऽपि बाधनार्थम्।

१९१०। अण्च।५।२।१०३। योगविभाग उत्तरार्थः। तापसः। साहस्रः। 'ज्योत्स्ना-दिभ्य उपसंख्यानम्' (वा ३१९७)। ज्यौत्स्नः। तामिस्रः।

१९११। सिकताशर्कराभ्यां च।५।२।१०४। सैकतो घटः। शार्करः।

१९१२। देशे लुबिलचौ च। ५। २। १०५। चादण्मतुप्च। सिकताः सन्त्यस्मिं
सिकताः–सिकतिलः–सैकतः–सिकतावान्। एवं शर्करेत्यादि।

१९१३। दन्त उन्नत उरच्। ५। २। १०६। उन्नता दन्ताः सन्त्यस्य दन्तुरः।

१९१४। ऊषसुषिमुष्कमधो रः। ५। २। १०७। ऊषरः। सुषिरः। मुष्कोऽण्ड
ष्करः। मधु माधुर्यम्–मधुरः। 'रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्' (वा ३१९८)। ख
मुखरः। कुञ्जो हस्तिहनुः। कुञ्जरः। 'नगपांसुपाण्डुभ्यश्च' (वा ३१९९)। नगरम्। पांसु
पाण्डुरः। पाण्डरशब्दस्त्वव्युत्पन्न एव। 'कच्छ्वा ह्रस्वत्वं च' (वा ३२००)। कच्छुरः।

१९१५। द्युद्रुभ्यां मः। ५। २। १०८। द्युमः। द्रुमः।

१९१६। केशाद्वोऽन्यतरस्याम्। ५। २। १०९। प्रकृतेनान्यतरस्यां ग्रहणेन म
सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम्। केशवः–केशी–केशिकः–केशवान्। 'अन्येभ्यो
दृश्यते' (वा ३२१०)। मणिवो नागविशेषः। हिरण्यवो निधिविशेषः। 'अर्णसो लोपश्च'
५०९३)। अर्णवः।

१९१७। गाण्ड्यजगात्संज्ञायाम्। ५। २। ११०। ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्दे
गाण्डिवम्। गाण्डीवमर्जुनस्य धनुः। अजगवं पिनाकः।

१९१८। काण्डाण्डादीरन्नीरचौ। ५। २। १११। काण्डीरः। आण्डीरः।

१९१९। रजःकृष्यासुतिपरिषदो वलच्। ५। २। ११२। रजस्वला स्त्री। कृषीव
'वले' (सू १०४०) इति दीर्घः। आसुतीवलः। शौण्डिकः। परिषद्वलः। 'पर्षत्' इति पा
न्तरम्। पर्षद्वलम्। 'अन्येभ्योऽपि दृश्यते' (वा ३२१०)। भ्रातृवलः। पुत्रवलः। शत्रुव
'वले' (सू १०४०) इत्यत्र 'संज्ञायाम्' इत्यनुवृत्तेर्नेह दीर्घः।

१९२०। दन्तशिखात्संज्ञायाम्। ५। २। ११३। दन्तावलो हस्ती। शिखावलः के

१९२१। ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः। ५।
११४। मत्वर्थे निपात्यन्ते। ज्योतिष उपधालोपो नश्च प्रत्ययः। ज्योत्स्ना। तमस उ
धाया इत्वं रश्च। तमिस्रा। स्त्रीत्वमतन्त्रम्। तामिस्रम्। शृङ्गादिनच्। शृङ्गिणः। ऊ
वलच्। तेन बाधा माभूदिति विनिरपि। ऊर्जस्वी। ऊर्जस्वलः। ऊर्जोऽसुगागम इति
स्तु चिन्त्या। 'ऊर्जस्वती' इति वदसुन्नन्तेनैवोपपत्तेः। गोशब्दान्मिनिः। गोमी। मलद
दिनच्। मलिनः। ईमसच। मलीमसः।

१९२२। अत इनिठनौ। ५। २। ११५। दण्डी–दाण्डिकः।

१९२३। व्रीह्यादिभ्यश्च। ५। २। ११६। व्रीही–व्रीहिकः। न च सर्वेभ्यो व्रीह्या
इनिठनाविष्येते। किं तर्हि। 'शिखामालासंज्ञादिभ्य इनिः, यवखदादिभ्य इकः' (वा ३२
अन्येभ्य उभयम्।

१९२४। तुन्दादिभ्य इलच्च। ५। २। ११७। चादिनिठनौ मतुप्च। तुन्दिलः–तु
तुन्दिकः–तुन्दवान्। उदर। पिचण्ड। यव। व्रीहि। 'स्वाङ्गाद्विवृद्धौ' (ग सू १२४) विवृ
पाधिकात्स्वाङ्गवाचिन इलजादयः स्युः। विवृद्धौ कर्णौ यस्य स कर्णिलः–कर्णी–कर्णि
कर्णवान्।

---

१. भाष्ये न दृश्यते–इति शेखरकृत्। रूपसिद्धिस्तु पृषोदरादित्वात्।

१९२५ । एकगोपूर्वाट्ठञ्नित्यम् । ५ । २ । ११८ । एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ।

१९२६ । शतसहस्रान्ताच्च निष्कात् । ५ । २ । ११९ । निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ्स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ।

१९२७ । रूपादाहतप्रशंसयोर्यप् । ५ । २ । १२० । आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । 'आहत–' इति किम् । रूपवान् । 'अन्येभ्योऽपि दृश्यते (वा ३२१०) । हिम्याः पर्वताः । गुण्या ब्राह्मणाः ।

१९२८ । अस्मायामेधास्रजो विनिः । ५ । २ । १२१ । यशस्वी–यशस्वान् । मायावी । व्रीह्यादिपाठादिनिठनौ । मायी–मायिकः । क्विन्नन्तत्वाकुः । स्रग्वी । 'आमयस्योपसंख्यानं दीर्घश्च' (वा ३२१३) । आमयावी । 'शृङ्गवृन्दाभ्यामारकन्' (वा ३२१४) । शृङ्गारकः । वृन्दारकः । 'फलबर्हाभ्यामिनच्' (वा ३२१५) । फलिनः । बर्हिणः । 'हृदयाच्चालुरन्यतरस्याम्' (वा ३२१६) । इन्ठनौ मतुप्च । हृदयालुः–हृदयी–हृदयिकः–हृदयवान् । 'शीतोष्णतृप्रेभ्यस्तदसहने–' (वा ३२१७) । शीतं न सहते शीतालुः । उष्णालुः । 'स्फायितञ्चि' इति रक् । तृप्रः पुरोडाशः, तं न सहते तृप्रालुः । 'तृप्रं दुःखम्' इति माधवः । 'हिमाच्चेलुः' (वा ३२१८) । हिमं न सहते हिमेलुः । 'बलादूलः' (वा ३२१९) । बलं न सहते बलूलः । 'वातात्समूहे च' (वा ३२२०) । वातं न सहते वातस्य समूहो वा वातूलः । 'तप्पर्वमरुद्भ्याम्' (वा ३२२१) । पर्वतः । मरुत्तः ।

१९२९ । ऊर्णाया युस् । ५ । २ । १२३ । सित्वात्पदत्वम् । ऊर्णायुः । अत्र 'छन्दसि' इति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि 'अहंशुभमोः–' (सू. १९४६) इत्यत्रैवोर्णाग्रहणं कुर्यात् ।

१९३० । वाचो ग्मिनिः । ५ । २ । १२४ । वाग्मी ।

१९३१ । आलजाटचौ बहुभाषिणि । ५ । २ । १२५ । 'कुत्सित इति वक्तव्यम्' (वा ३२२३) । कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्मीत्येव ।

१९३२ । स्वामिन्नैश्वर्ये । ५ । २ । १२६ । ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ।

१९३३ । अर्शआदिभ्योऽच् । ५ । २ । १२७ । अर्शांस्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ।

१९३४ । द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः । ५ । २ । १२८ । द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापो रोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । 'प्राणिस्थात्' किम् । पुष्पफलवान्घटः । 'प्राण्यङ्गान्न' । पाणिपादवती । 'अतः' इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् ।

१९३५ । वातातीसाराभ्यां कुक्च । ५ । २ । १२९ । चादिनिः । वातकी । अतीसारकी । 'रोगे चायमिष्यते' । नेह । वातवती गुहा । 'पिशाचाच्च' (वा ३२२४) । पिशाचकी ।

१९३६। वयसि पूरणात्। ५। २। १३०। पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयो-द्योत्ये। मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः। ठन्बाधनार्थमिदम्। 'वयसि' किम्। पञ्चमवान्ग्रामः।

१९३७। सुखादिभ्यश्च। ५। २। १३१। इनिर्मत्वर्थे। सुखी। दुःखी। 'माला क्षेपे' (ग सू ११६)। माली।

१९३८। धर्मशीलवर्णान्ताच्च। ५। २। १३२। धर्माद्यन्तादिनिर्मत्वर्थे। ब्राह्मणधर्मी। ब्राह्मणशीली। ब्राह्मणवर्णी।

१९३९। हस्ताज्जातौ। ५। २। १३३। हस्ती। 'जातौ' किम्। हस्तवान्पुरुषः।

१९४०। वर्णाद्ब्रह्मचारिणि। ५। २। १३४। वर्णी।

१९४१। पुष्करादिभ्यो देशे। ५। २। १३५। पुष्करिणी। पद्मिनी। 'देशे' किम्। पुष्करवान्करी। 'बाहूरुपूर्वपदाद्बलात्' (वा ३२२५)। बाहुबली। ऊरुबली। 'सर्वादेः' (वा ३२२६)। सर्वधनी। सर्वबीजी। 'अर्थाच्चासंनिहिते' (वा ३२२७)। अर्थी। संनिहिते तु अर्थवान्। 'तदन्ताच्च' (वा ३२२८)। धान्यार्थी। हिरण्यार्थी।

१९४२। बलादिभ्यो मतुबन्यतरस्याम्। ५। २। १३६। बलवान्-बली। उत्साहवान्-उत्साही।

१९४३। संज्ञायां मन्माभ्याम्। ५। २। १३७। मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे। प्राथिमिनी। दामिनी। होमिनी। सोमिनि। 'संज्ञायाम्' किम्। सोमवान्।

१९४४। कंशंभ्यां बभयुस्तितुतयसः। ५। २। १३८। 'कम्' 'शम्' इति मान्तौ। 'कम्' इत्युदकसुखयोः। 'शम्' इति सुखे। आभ्यां सप्त प्रत्ययाः स्युः। युस्यसोः सकारः पदत्वार्थः। कंवः। कंभः। कंवः। कंतिः। कंतुः। कंतः। कंयः। शंवः। शंभः। शंयुः। शंतिः। शंतुः। शंयः। अनुस्वारस्य वैकल्पिकः परसवर्णः। वकारयकारपरसवर्णः सिकौ वयौ।

१९४५। तुन्दिवलिवटेर्भः। ५। २। १३९। वृद्धा नाभिस्तुन्दिः। 'मूर्धन्योपधोऽपि' इति माधवः। तुन्दिभः। वलिभः। वटिभः। पामादित्वाद्वलिनोऽपि।

१९४६। अहंशुभमोर्युस्। ५। २। १४०। 'अहम्' इति मान्तमव्ययमहंकारे। 'शुभ'मिति शुभे। अहंयुः, अहंकारवान्। शुभंयुः, शुभान्वितः।

इति तद्धितमत्वर्थीयप्रकरणम्।

अथ तद्धितप्राग्दिशीयप्रकरणम्।

१९४७। प्राग्दिशो विभक्तिः। ५। ३। १। दिक्छब्देभ्य इत्यतः प्रागवक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः। अथ स्वार्थिकाः प्रत्ययाः। 'समर्थानाम्' इति 'प्रथमात्' इति च निवृत्तम्। 'वा' इति त्वनुवर्तत एव।

१९४८। किंसर्वनामबहुभ्योऽद्व्यादिभ्यः। ५। ३। २। किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते।

१९४९। इदम इश्। ५। ३। ३। प्राग्दिशीये परे।

१९५० । एतेतौ रथोः । ५ । ३ । ४ । इदम्शब्दस्य 'एत' 'इत' इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । इशोऽपवादः ।

१९५१ । एतदोऽन् । ५ । ३ । ५ । योगविभागः कर्तव्यः । एतदः एतेतौ स्तो रथोः । 'अन्' । 'एतदः' इत्येव । अनेकाल्त्वात्सर्वादेशः । 'नलोपः प्रातिपदिकान्तस्य' (सू २३६) ।

१९५२ । सर्वस्य सोऽन्यतरस्यां दि । ५ । ३ । ६ । प्राग्दिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ।

१९५३ । पञ्चम्यास्तसिल् । ५ । ३ । ७ । पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल्स्याद्वा ।

१९५४ । कु तिहोः । ७ । २ । १०४ । किमः कु स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु द्वाभ्याम् ।

१९५५ । तसेश्च । ५ । ३ । ८ । किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् ।

१९५६ । पर्यभिभ्यां च । ५ । ३ । ९ । आभ्यां तसिल्स्यात् । 'सर्वोभयार्थाभ्यामेव' (वा ३२४०) । परितः सर्वत इत्यर्थः । अभित उभयत इत्यर्थः ।

१९५७ । सप्तम्यास्त्रल् । ५ । ३ । १० । कुत्र । यत्र । तत्र । बहुत्र ।

१९५८ । इदमो हः । ५ । ३ । ११ । त्रलोऽपवादः । इशादेशः । इह ।

१९५९ । किमोऽत् । ५ । ३ । १२ । वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात् । पक्षे त्रल् ।

१९६० । क्वाति । ७ । २ । १०५ । किमः क्वादेशः स्यादति । क्व । कुत्र ।

१९६१ । वा ह च च्छन्दसि । ५ । ३ । १३ । 'कुह स्थः' । 'कुह जग्मथुः' ।

१९६२ । एतदस्त्रतसोस्त्रतसौ चानुदात्तौ । २ । ४ । ३३ । अन्वादेशविषय एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन्ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तारः स्मः ।

१९६३ । इतराभ्योऽपि दृश्यन्ते । ५ । ३ । १४ । पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । 'दृशिग्रहणाद्भवदादियोग एव' (वा ३२४४) । स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवानांप्रियः । आयुष्मान् ।

१९६४ । सर्वैकान्यकियत्तदः काले दा । ५ । ३ । १५ । सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले । सदा । सर्वदा । एकदा । अन्यदा । यदा । कदा । तदा । 'काले' किम् । सर्वत्र देशे ।

१९६५ । इदमो र्हिल् । ५ । ३ । १६ । सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । 'काले' किम् । इह देशे ।

१९६६ । अधुना । ५ । ३ । १७ । इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् । इश् । 'यस्य–' (सू ३११) इति लोपः । अधुना ।

१९६७ । दानीं च । ५ । ३ । १८ । इदानीम् ।

१९६८ । तदो दा च । ५ । ३ । १९ । तदा–तदानीम् । 'तदो दावचनमनर्थकं विहितत्वात्' (वा ३२४३) ।

१९६९ । अनद्यतने र्हिलन्यतरस्याम् । ५ । ३ । २१ । कर्हि—कदा । यर्हि—यदा । तर्हि—तदा । एतस्मिन्काल एतर्हि ।

१९७० । सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः । ५ । ३ । २२ । एते निपात्यन्ते । 'समानस्य सभावो द्यश्चाहनि' (वा ३२४५) । समानेऽहनि सद्यः । 'पूर्वपूर्वतरयोः पर उदारी च संवत्सरे' (वा ३२४६) । पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि । 'इदम इश् समसण्प्रत्ययश्च संवत्सरे' (वा ३२४७) । अस्मिन्संवत्सरे ऐषमः । 'परस्मादेद्यव्यहनि' (वा ३२४८) परस्मिन्नहनि परेद्यवि । 'इदमोऽश् द्यश्च' (वा ३२४९) अस्मिन्नहनि अद्य । 'पूर्वादिभ्योऽष्टभ्योऽहन्येद्युस्' (वा ३२५०) । पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्नोरुभयेद्युः । 'द्युश्चोभयाद्वक्तव्यः' (वा ३२५१) । उभयद्युः ।

१९७१ । प्रकारवचने थाल् । ५ । ३ । २३ । प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे । तेन प्रकारेण तथा । यथा ।

१९७२ । इदमस्थमुः । ५ । ३ । २४ । थालोऽपवादः । 'एतदो वाच्यः' (वा ३२५२) । अनेन एतेन वा प्रकारेण इत्थम् ।

१९७३ । किमश्च । ५ । ३ । २५ । केन प्रकारेण कथम् ।

इति तद्धितप्राग्दिशीयप्रकरणम् ।

अथ तद्धितप्रागिवीयप्रकरणम् ।

१९७४ । दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः । ५ । ३ । २७ । सप्तम्याद्यन्तेभ्यो दिशि रूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिप्रत्ययः स्यात् ।

१९७५ । पूर्वाधरावराणामसि पुरधवश्चैषाम् । ५ । ३ । ३९ । एभ्योऽस्तात्यर्थे असिप्रत्ययः स्यात् । तद्योगे चैषां क्रमात् 'पुर' 'अध्' 'अव्' इत्यादेशाः स्युः ।

१९७६ । अस्ताति च । ५ । ३ । ४० । अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां—पूर्वस्याः—पूर्वा वा दिक् । पुरः—पुरस्तात् । अधः—अधस्तात् । अवः—अवस्तात् ।

१९७७ । विभाषावरस्य । ५ । ३ । ४१ । अवरस्यास्तातौ परेऽव् स्याद्वा । अवस्तात्, अवरस्तात् । एवं देशे काले च । 'दिशि रूढेभ्यः' किम् । ऐन्द्र्यां वसति । 'सप्तम्याद्यन्तेभ्यः' किम् । पूर्वं ग्रामं गतः । 'दिगादिवृत्तिभ्यः' किम् । पूर्वस्मिन्गुरौ वसति । 'अस्ताति च' (सू १९७६) इति ज्ञापकादसिरस्तातिं न बाधते ।

१९७८ । दक्षिणोत्तराभ्यामतसुच् । ५ । ३ । २८ । अस्तातेरपवादः । दक्षिणतः । उत्तरतः ।

१९७९ । विभाषा परावराभ्याम् । ५ । ३ । २९ । परतः । अवरतः । परस्तात् । अवरस्तात् ।

१९८० । अञ्चेर्लुक् । ५ । ३ । ३० । अञ्चत्यन्तादिक्छब्दादस्तातेर्लुक् स्यात् । 'लुक्तद्धितलुकि' (सू. १४०८) । प्राच्यां प्राच्याः प्राची वा दिक्प्राक् । उदक् । एवं देशे काले

१९८१ । उपर्युपरिष्टात् । ५ । ३ । ३१ । अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ । उपरि–उपरिष्टाद्वा वसति आगतो रमणीयं वा ।

१९८२ । पश्चात् । ५ । ३ । ३२ । अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ।

१९८३ । उत्तराधरदक्षिणादातिः । ५ । ३ । ३४ । उत्तरात् । अधरात् । दक्षिणात् ।

१९८४ । एनबन्यतरस्यामदूरेऽपञ्चम्याः । ५ । ३ । ३५ । उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचिदुत्तरादीननुवर्त्य दिक्छब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् । अपरेण ग्रामम् ।

१९८५ । दक्षिणादाच् । ५ । ३ । ३६ । अस्तातेर्विषये । दक्षिणा वसति । 'अपञ्चम्याः' इत्येव । दक्षिणादागतः ।

१९८६ । आहि च दूरे । ५ । ३ । ३७ । दक्षिणाद्दूरे आहि स्यात् । चादाच् । दक्षिणाहि दक्षिणा ।

१९८७ । उत्तराच्च । ५ । ३ । ३८ । उत्तराहि–उत्तरा ।

१९८८ । संख्याया विधार्थे धा । ५ । ३ । ४२ । क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ।

१९८९ । अधिकरणविचाले च । ५ । ३ । ४३ । द्रव्यस्य संख्यान्तरापादने संख्याया धा स्यात् । एकं राशिं पञ्चधा कुरु ।

१९९० । एकाद्धो ध्यमुञन्यतरस्याम् । ५ । ३ । ४४ । ऐकध्यम्–एकधा ।

१९९१ । द्वित्र्योश्च धमुञ् । ५ । ३ । ४५ । आभ्यां 'धा' इत्यस्य धमुञ्स्याद्वा । द्वैधम्–द्विधा । त्रैधम्–त्रिधा । 'धमुञन्तात्स्वार्थे डदर्शनम्' (वा ३२६०) । पथि द्वैधानि ।

१९९२ । एधाच्च । ५ । ३ । ४६ । द्वेधा । त्रेधा ।

१९९३ । याप्ये पाशप् । ५ । ३ । ४७ । कुत्सितो भिषक् भिषक्पाशः ।

१९९४ । पूरणाद्भागे तीयादन् । ५ । ३ । ४८ । द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः । 'तीयादीकक्स्वार्थे वा वाच्यः' (वा २६९१) । द्वैतीयीकः–द्वितीयः । तार्तीयीकः–तृतीयः । 'न विद्यायाः' (वा २६९२) । द्वितीया तृतीया विद्येत्येव ।

१९९५ । प्रागेकादशभ्योऽछन्दसि । ५ । ३ । ४९ । पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । पञ्चमः ।

१९९६ । षष्ठाष्टमाभ्यां ञ च । ५ । ३ । ५० । चादन् । षष्ठो भागः षाष्ठः–षष्ठः । आष्टमः–अष्टमः ।

१९९७ । मानपश्वङ्गयोः कन्लुकौ च । ५ । ३ । ५१ । षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । अस्यानो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः–षाष्ठः । अष्टमः–आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र आनौ नित्याविति ज्ञापयति ।

१९९८ । एकादाकिनिच्चासहाये । ५ । ३ । ५२ । चात्कन्लुकौ । एकः–एकाकी–एककः ।

१९९९ । भूतपूर्वे चरट् । ५ । ३ । ५३ । आढ्यो भूतपूर्व आढ्यचरः ।

२००० । षष्ठ्या रूप्य च । ५ । ३ । ५४ । षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् । कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः—कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुं० । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ।

२००१ । अतिशायने तमबिष्ठनौ । ५ । ३ । ५५ । अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः आढ्यतमः । लघुतमो लघिष्ठः ।

२००२ । तिङश्च । ५ । ३ । ५६ । तिङन्तादतिशये द्योत्ये तमप्स्यात् ।

२००३ । तरप्तमपौ घः । १ । १ । २२ । एतौ घसंज्ञौ स्तः ।

२००४ । किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । ५ । ४ । ११ । किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किन्तमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ।

२००५ । द्विवचनविभज्योपपदे तरबीयसुनौ । ५ । ३ । ५७ । द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुर्लघुतरः लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः—पटीयांसः ।

२००६ । अजादी गुणवचनादेव । ५ । ३ । ५८ । इष्ठन्नीयसुनौ गुणवचनादेव । प्रथिष्ठ-प्रथीयान् । नेह । पाचकतरः—पाचकतमः ।

२००७ । तुश्छन्दसि । ५ । ३ । ५९ । तृन्नतृजन्तादिष्ठन्नीयसुनौ स्तः ।

२००८ । तुरिष्ठेमेयःसु । ६ । ४ । १५४ । तृशब्दस्य लोपः स्यादिष्ठेमेयःसु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ।

२००९ । प्रशस्यस्य श्रः । ५ । ३ । ६० । अस्य श्रादेशः स्यादजाद्योः ।

२०१० । प्रकृत्यैकाच् । ६ । ४ । १६३ । इष्ठादिष्वेकाच्प्रकृत्या स्यात् । श्रेष्ठः-श्रेयान् ।

२०११ । ज्य च । ५ । ३ । ६१ । प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ।

२०१२ । ज्यादादीयसः । ६ । ४ । १६० । 'आदेः परस्य' (सू ४४) । ज्यायान् ।

२०१३ । वृद्धस्य च । ५ । ३ । ६२ । ज्यादेशः स्यादजाद्योः । ज्येष्ठः—ज्यायान् ।

२०१४ । अन्तिकबाढयोर्नेदसाधौ । ५ । ३ । ६३ । अजाद्योः । नेदिष्ठः-नेदीयान् । साधिष्ठः-साधीयान् ।

२०१५ । स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः ।६।४। १५६ । एषां यणादि परं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयस् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वाद्ध्रसिमा । क्षेपिमा । क्षोदिमा ।

२०१६ । प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः । ६ । ४ । १५७ । प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात्प्रेमेत्यादि ।

२०१७ । बहोर्लोपो भू च बहोः । ६ । ४ । १५८ । बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा—भूयान् ।

२०१८। इष्ठस्य यिट् च। ६।४।१५९। बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च। भूयिष्ठः।

२०१९। युवाल्पयोः कनन्यतरस्याम्। ५।३।६४। एतयोः कनादेशो वा स्यादिष्ठेयसोः। कनिष्ठः। कनीयान्। पक्षे यविष्ठः। अल्पिष्ठ इत्यादि।

२०२०। विन्मतोर्लुक्। ५।३।६५। विनो मतुपश्च लुक्स्यादिष्ठेयसोः। अतिशयेन स्रग्वी। स्रजिष्ठः—स्रजीयान्। अतिशयेन त्वग्वान्—त्वचिष्ठः—त्वचीयान्।

२०२१। प्रशंसायां रूपप्। ५।३।६६। सुबन्तात्तिङन्ताच्च। प्रशस्तः पटुः पटुरूपः। प्रशस्तं पचति पचतिरूपम्।

२०२२। ईषदसमाप्तौ कल्पब्देश्यदेशीयरः। ५।३।६७। ईषदूनो विद्वान्विद्वत्कल्पः। यशस्कल्पम्। यजुःकल्पम्। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्।

२०२३। विभाषा सुपो बहुच्पुरस्तात्तु। ५।३।६८। ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः। ईषदूनः पटुर्बहुपटुः। पटुकल्पः। 'सुपः' किम्। यजतिकल्पम्।

२०२४। प्रकारवचने जातीयर्। ५।३।६९। प्रकारवति चायम्। थाल्तु प्रकारमात्रे। पटुप्रकारः पटुजातीयः।

२०२५। प्रागिवात्कः। ५।३।७०। 'इवे प्रतिकृतौ' (सू २०५२) इत्यतः प्राक्काधिकारः।

२०२६। अव्ययसर्वनाम्नामकच्प्राक्टेः। ५।३।७१। 'तिङश्च' (सू २००२) इत्यनुवर्तते।

२०२७। कस्य च दः। ५।३।७२। कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च।

२०२८। अज्ञाते। ५।३।७३। कस्यायमश्वोऽश्वकः। उच्चकैः। नीचकैः। सर्वके। विश्वके। 'ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्' अन्यत्र तु सुबन्तस्य टेः प्रागकच्' (वा ३३८४)। युवकयोः। आवकयोः। युष्मकासु। अस्मकासु। युष्मकाभिः। अस्मकाभिः। 'ओकार—' इत्यादि किम्। त्वयका। मयका। 'अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः' (वा ३३८५)। मित्वादन्त्यादचः परः। तूष्णीकामास्ते। 'शीले को मलोपश्च (वा ३३८६)। तूष्णींशीलस्तूष्णीकः। पचतकि। जल्पतकि। धकित्। हिरकुत्।

२०२९। कुत्सिते। ५।३।७४। कुत्सितोऽश्वोऽश्वकः।

२०३०। संज्ञायां कन्। ५।३।७६। कुत्सिते कन्स्यात्तदन्तेन चेत्संज्ञा गम्यते शूद्रकः। राधकः। स्वरार्थं वचनम्।

२०३१। अनुकम्पायाम्। ५।३।७६। पुत्रकः। अनुकम्पितः पुत्र इत्यर्थः।

२०३२। नीतौ च तद्युक्तात्। ५।३।७७। सामदानादिरूपा नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्प्रत्ययः स्यात्। हन्त ते धानकाः। गुडकाः। एहकि। अद्धकि। पूर्वेणानुकम्प्यमानात्प्रत्ययः। अनेन तु परम्परासंबन्धेऽपीति विशेषः।

२०३३। बह्वचो मनुष्यनाम्नष्ठज्वा। ५।४।७८। पूर्वसूत्रद्वयविषये।

२०३४। घनिलचौ च। ५।३।७९। तत्रैव।

२०३५। ठाजादावूर्ध्वं द्वितीयादचः । ५ । ३ । ८३ । अस्मिन्प्रकरणे यष्ठोऽ
प्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो दे
देविकः—देवियः—देविलः—देवदत्तकः । अनुकम्पितो वायुदत्तो वायुकः । ठग्रहणमुको
यत्वे कविधानार्थम् । वायुदत्तः—वायुकः । पितृकः । 'चतुर्थादच ऊर्ध्वस्य लोपो व
(वा ३२९६) । अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । 'अनजादौ च विभाषा
वक्तव्यः' (वा ३२९७) । देवदत्तकः—देवकः । 'लोपः पूर्वपदस्य च' (वा ३२९८
दत्तिकः—दत्तियः—दत्तिलः—दत्तकः । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः'
३२९९) । देवदत्तः—दत्तः देवः । सत्यभामा—भामा सत्या । 'उवर्णाल्ल इलस्य च
३३०३) । भानुदत्तः—भानुलः । '[1]ऋवर्णादपि' (वा ५०५४) । सावित्रियः । सावितृलः ।

'चतुर्थादनजादौ च लोपः पूर्वपदस्य च ।
अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥' (वा ३२९६–३३००)

ल इति लोपसंज्ञा प्राचाम् ।

२०३६ । प्राचामुपादेरडज्वुचौ च । ५ । ३ । ८० । उपशब्दपूर्वात्प्रातिपदिकात्पू
अडज्वुचू एतौ स्तः । चाद्यथाप्राप्तम् । प्राचां ग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्त उ
उपकः—उपिकः—उपियः—उपिलः—उपेन्द्रदत्तकः । षड्रूपाणि ।

२०३७ । जातिनाम्नः कन् । ५ । ३ । ८१ । 'मनुष्यनाम्नः' इत्येव । जातिशब्दे
मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । राक
'द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः' (वा ३३०३) । कहोडः । कहिकः । 'एक
पूर्वपदानामुत्तरपदलोपो वक्तव्यः' (वा ३३०६) । वागाशीर्दत्तः । वाचिकः । कथं प
लिदत्तः षडिक इति । 'षषष्ठाजादिवचनात्सिद्धम्' (वा ३३०७) ।

२०३८ । शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् । ५ । ३ । ८४ । ए
ष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शे
दत्तः—शेवलिकः—शेवलियः—शेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिक

२०३९ । अजिनान्तस्योत्तरपदलोपश्च । ५ । ३ । ८२ । अजिनान्तान्मनुष्यनाम्नो
म्पायां कन् । तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ।

२०४० पे । ५ । ३ । ८५ । अल्पं तैलं तैलिकम् ।

२०४१ । ह्रस्वे । ५ । ३ । ८६ । ह्रस्वो वृक्षो वृक्षकः ।

२०४२ । संज्ञायां कन् । ५ । ३ । ८७ । ह्रस्वहेतुका या संज्ञा तस्यां गम्य
कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ।

२०४३ । कुटीशमीशुण्डाभ्यो रः । ५ । ३ । ८८ । ह्रस्वा कुटी कुटीरः । श
शुण्डारः ।

२०४४ । कुत्वा डुपच् । ५ । ३ । ८९ । ह्रस्वा कुतूः कुतुपः । 'कुतूः कृत्तेः स्
ह्रस्वा सा कुतुपः पुमान्' इत्यमरः ।

---

१. भाष्ये न दृष्टम्—इति शेखरकृत ।

२०४५ । कासूगोणीभ्यां ष्टरच् । ५ । ३ । ९० । आयुधविशेषः कासूः । ह्रस्वा सा कासूतरी । गोणीतरी ।

२०४६ । वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे । ५ । ३ । ९१ । वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ।

२०४७ । किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् । ५ । ३ । ९२ । अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषया कः । यः । सः ।

२०४८ । वा बहूनां जातिपरिप्रश्ने डतमच् । ५ । ३ । ९३ । बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात् । 'जातिपरिप्रश्ने' इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः । किमोऽस्मिन्विषये डतरजपि । कतरः ।

२०४९ । एकाच्च प्राचाम् । ५ । ३ । ९४ । डतरच् डतमच् स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ।

२०५० । अवक्षेपणे कन् । ५ । ३ । ९५ । व्याकरणेन गर्वितः व्याकरणकः । येनेतर कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सितं तु 'कुत्सिते' (सू २०२९) इत्यस्य ।

इति तद्धितप्रागिवीयप्रकरणम् ।

अथ तद्धिततद्राजप्रकरणम् ।

२०५१ । इवे प्रतिकृतौ । ५ । ३ । ९६ । कन्स्यात् । अश्व इव प्रतिकृतिः अश्वकः । 'प्रतिकृतौ' किम् । गौरिव गवयः ।

२०५२ । संज्ञायां च । ५ । ३ । ९७ । इवार्थे कन्स्यात्समुदायश्चेत्संज्ञा । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा अश्वकः । उष्ट्रकः ।

२०५३ । लुम्मनुष्ये । ५ । ३ । ९८ । संज्ञायां च विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । 'चञ्चा तृणमयः पुमान्' । चञ्चेव मनुष्यश्चञ्चा । वध्रिका ।

२०५४ । जीविकार्थे चापण्ये । ५ । ३ । ९९ । जीविकार्थं यदविक्रीयमाणं तस्मिन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । 'अपण्ये' किम् । हस्तिकान्विक्रीणीते ।

२०५५ । देवपथादिभ्यश्च । ५ । ३ । १०० । कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ।

२०५६ । वस्तेर्ढञ् । ५ । ३ । १०१ । इवेत्यनुवर्तत एव । 'प्रतिकृतौ' इति निवृत्तम् । वस्तिरिव वास्तेयम्-वास्तेयी ।

२०५७ । शिलाया ढः । ५ । ३ । १०२ । 'शिलायाः' इति योगविभागाड्ढञपीत्येके । शिलेव शिलेयम्-शैलेयम् ।

२०५८ । शाखादिभ्यो यत् । ५ । ३ । १०३ । शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ।

२०५९ । द्रव्यं च भव्ये । ५ । ३ । १०४ । द्रव्यमयं ब्राह्मणः ।

२०६० । कुशाग्राच्छः । ५ । ३ । १०५ । कुशाग्रमिव कुशाग्रीया बुद्धिः ।

२०६१ । समासाच्च तद्विषयात् । ५ । ३ । १०६ । इवार्थविषयात्समासाच्छः स्या काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशश्चोरसमागम इति समास तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फ तोऽर्थः ।

२०६२ । शर्करादिभ्योऽण् । ५ । ३ । १०७ । शर्करेव शार्करम् ।

२०६३ । अङ्गुल्यादिभ्यष्ठक् । ५ । ३ । १०८ । अङ्गुलीव अङ्गुलिकः । भ मारुजिकः ।

२०६४ । एकशालायाष्ठजन्यतरस्याम् । ५ । ३ । १०९ । एकशालाशब्दा ठञ्वा । पक्षे ठक् । एकशालेव एकशालिकः-ऐकशालिकः ।

२०६५ । कर्कलोहितादीकक् । ५ । ३ । ११० । कर्कः शुक्लोऽश्वः स इव कार्की लौहितीकः स्फटिकः ।

२०६६ । पूगाञ्ञ्योऽग्रामणीपूर्वात् । ५ । ३ । ११२ । इवार्थो निवृत्तः । नानाज अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगास्तद्वाचकात्स्वार्थे ञ्यः स्यात् । लौहितध्व 'व्रातच्फञोरस्त्रियाम्'(सू ११००) । व्रातः । कापोतपाक्यः । च्फञ् । कौञ्जायन्यः । ब्राध्न

२०६७ । आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् । ५ । ३ । वाहीकेषु य आयुधजीविसंघस्तद्वाचिनः स्वार्थे ञ्यट् । क्षौद्रक्यः । मालव्यः । टित्त्वा क्षौद्रकी । 'आयुध-' इति किम् । मल्लाः । 'संघ-' इति किम् । सम्राट् । 'वाहीकेषु' इ शबराः । 'अब्राह्मण-' इति किम् । गोपालवाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्र राजन्ये स्वरूपग्रहणम् ।

२०६८ । वृकाट्टेण्यण् । ५ । ३ । ११५ । आयुधजीविसंघवाचकात्स्वार्थे । वार्केण 'आयुध-' इति किम् । जातिशब्दान्मा भूत् ।

२०६९ । दामन्यादित्रिगर्तषष्ठाच्छः । ५ । ३ । ११६ । दामन्यादिभ्यस्त्रिगर्त आयुधजीविसंघवाचिभ्यः स्वार्थे छः स्यात् । त्रिगर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ।

'आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ।
क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥'

दामनीयः । दामनीयौ । दामनयः । औलपि-औलपीयः । त्रिगर्त-कौण्डोपरथ दाण्डकीयः ।

२०७० । पर्श्वादियौधेयादिभ्यामणञौ । ५ । ३ । ११७ । आयुधजीविसंघ एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौ

२०७१ । अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् ५ । ३ । ११८ । अभिजिदादिभ्योऽण्णन्तेभ्यः स्वार्थे यञ्स्यात् । अभिजितोऽपत्यमाभि वैदभृत्यः । शालावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः ।

२०७२ । ञ्यादयस्तद्राजाः । ५ । ३ । ११९ । 'पूगाञ्ञ्यः-' (सू २०६६)

डाक एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः ब्रध्नायना इत्यादि ।

२०७३ । पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च । ५ । ४ । १ । लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । 'पादः पत्' (सू ४१४) । 'तद्धितार्थ–' (सू ७२८) इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् । 'पादशतग्रहणमनर्थकमन्यत्रादि दर्शनात्' (वा ३३१४) । द्विमोदकिकाम् ।

२०७४ । दण्डव्यवसर्गयोश्च । ५ । ४ । २ । वुन्स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकां द्विशतिकां व्यवसृजति ददातीत्यर्थः ।

२०७५ । स्थूलादिभ्यः प्रकारवचने कन् । ५ । ४ । ३ । जातीयरोऽपवादः । स्थूलकः । अणुकः । 'चञ्चद्बृहतोरुपसंख्यानम्' (वा ३३१५) । चञ्चत्कः । बृहत्कः । 'सुराया अहौ' (ग सू १३०) । सुरावर्णोऽहिः सुरकः ।

२०७६ । अनत्यन्तगतौ क्तात् । ५ । ४ । ४ । छिन्नकम् । भिन्नकम् । अभिन्नकम् ।

२०७७ । न सामिवचने । ५ । ४ । ५ । सामिपर्याय उपपदे क्तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन्न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् ।

२०७८ । बृहत्या आच्छादने । ५ । ४ । ६ । कन्स्यात् । 'द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा' इत्यमरः । 'आच्छादने' किम् । बृहती छन्दः ।

२०७९ । अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः । ५ । ४ । ७ । स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्निति आशितंगवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । 'अन्येऽपि केचित्स्वार्थिकाः प्रत्यया नित्यमिष्यन्ते' । 'तमबादयः प्राक्कनः । ञ्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्च' इति [भाष्यम्] ।

२०८० । विभाषाञ्चेरदिक्स्त्रियाम् । ५ । ४ । ८ । अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः स्याद्वा स्वार्थे । प्राक्–प्राचीनम् । प्रत्यक्–प्रतीचीनम् । अवाक्–अवाचीनम् । 'निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः' इत्यमरः । अर्वन्तमञ्चतीति अर्वाक् । अर्वाचीनम् । 'अदिक्स्त्रियाम्' किम् । प्राची दिक् । उदीची दिक् । 'दिग्ग्रहणम्' किम् । प्राचीना ब्राह्मणी । 'स्त्रीग्रहणम्' किम् । प्राचीनं ग्रामादाम्राः ।

२०८१ । जात्यन्ताच्छ बन्धुनि । ५ । ४ । ९ । ब्राह्मणजातीयः । 'बन्धुनि' किम् । ब्राह्मणजातिः शोभना । जातिर्व्यञ्जकं द्रव्यं बन्धु ।

२०८२ । स्थानान्ताद्विभाषा सस्थानेनेति चेत् । ५ । ४ । १० । सस्थानेन तुल्येन चेत्स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः–पितृस्थानः । 'सस्थानेन' किम् । गोः स्थानम् ।

२०८३ । अनुगादिनष्ठक् । ५ । ४ । १३ । अनुगदतीत्यनुगादी । स एवानुगादिकः ।

२०८४ । विसारिणो मत्स्ये । ५ । ४ । १६ । अण्स्यात् । वैसारिणः । 'मत्स्ये' इति किम् । विसारी देवदत्तः ।

२०८५ । संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् । ५ । ४ । १७ । अभ्या
जैन्म, क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच्स्यात् । पञ्चकृत्वो भुङ्क्ते । 'संख्या
किम् । भूरिवारान्भुङ्क्ते ।

२०८६ । द्वित्रिचतुर्भ्यः सुच् । ५ । ४ । १८ । कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रि
'रात्सस्य' (सू २८०) । चतुः ।

२०८७ । एकस्य सकृच्च । ५ । ४ । १९ । सकृदित्यादेशः स्यात् । चात्सुच् । सकृ
'संयोगान्तस्य–'(सू ५४) इति सुचो लोपः । न तु 'हल्ङ्याप्–'(सू २५२) इति । अभ
त्यत्र सिच इव सुचोऽपि तदयोगात् ।

२०८८ । विभाषा बहोर्धाविप्रकृष्टकाले । ५ । ४ । २० । अविप्रकृष्ट आसन्नः । ब
दिवसस्य भुङ्क्ते । 'आसन्नकाले' किम् । बहुकृत्वो मासस्य भुङ्क्ते ।

२०८९ । तत्प्रकृतवचने मयट् । ५ । ४ । २१ । प्राचुर्येण प्रस्तुतं प्रकृतं तस्य
प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् ।
मयी । द्वितीयेऽन्नमयो यज्ञः । अपूपमयं पर्व ।

२०९० । समूहवच्च बहुषु । ५ । ४ । २२ । सामूहिकाः प्रत्यया अतिदिश्यन्ते
यट् । मोदकाः प्रकृताः । मौदकिकम्–मोदकमयम् । शाष्कुलिकम्–शष्कुलीमयम् ।
येऽर्थे मौदकिको यज्ञः–मोदकमयः ।

२०९१ । अनन्तावसथेतिहभेषजाञ्ञ्यः । ५ । ४ । २३ । अनन्त एवानन्
आवसथ एवावसथ्यम् । 'इतिह' इति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भेष

२०९२ । देवतान्तात्तादर्थ्ये यत् । ५ । ४ । २४ । तदर्थ एव तादर्थ्यम् । स्वार्थे
अग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम् ।

२०९३ । पादार्घाभ्यां च । ५ । ४ । २५ । पादार्थमुदकं पाद्यम् । अर्घ्यम् । 'नव
आदेशो नूत्नप्तनप्खाश्च प्रत्यया वक्तव्याः' (वा ३३२७) । नूत्नम्–नूतनम्–नवीनम् ।
पुराणे प्रात्' (वा ३३२८) । पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः । चात्पूर्वोक्ताः ।
प्रत्नम्–प्रतनम्–प्रीणम् । 'भागरूपनामभ्यो धेयः' (वा ३३३०) । भागधेयम् । रूप
नामधेयम् । 'आग्नीध्रसाधारणादञ्' (वा ३३३४) । आग्नीध्रम् । साधारणम् । स्त्रि
आग्नीध्री । साधारणी ।

२०९४ । अतिथेर्ञ्यः । ५ । ४ । २६ । 'तादर्थ्ये' इत्येव । अतिथय इदमाति

२०९५ । देवात्तल् । ५ । ४ । २७ । देव एव देवता ।

२०९६ । अवेः कः । ५ । ४ । २८ । अविरेवाविकः ।

२०९७ । यावादिभ्यः कन् । ५ । ४ । २९ । याव एव यावकः । मणिकः ।

२०९८ । लोहितान्मणौ । ५ । ४ । ३० । लोहित एव मणिर्लोहितकः ।

२०९९ । वर्णे चानित्ये । ५ । ४ । ३१ । लोहितकः कोपेन । 'लोहिताल्लिङ्गबा
(वा ३३३२) । लोहितिका–लोहिनिका कोपेन ।

२१०० । रक्ते । ५ । ४ । ३२ । लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्क
'लिङ्गबाधनं वा' (वा ३३३२) इत्येव । लोहितिका–लोहिनिका शाटी ।

२१०१। कालाच्च।५।४।३३। 'वर्णे चानित्ये' (सू २०९९), 'रक्ते' (सू २१००) इति द्वयमनुवर्तते। कालकं मुखं वैलक्ष्येण। कालकः पटः। कालिका शाटी।

२१०२। विनयादिभ्यष्ठक्।५।४।३४। विनय एव वैनयिकः। सामयिकः। 'उपायो ह्रस्वत्वं च' (ग सू १४४)। औपयिकः।

२१०३। वाचो व्याहृतार्थायाम्।५।४।३५। संदिष्टार्थायां वाचि विद्यमानाद्वाक्छब्दात्स्वार्थे ठक्च स्यात्। 'संदेशवाग्वाचिकं स्यात्' इत्यमरः।

२१०४। तद्युक्तात्कर्मणोऽण्।५।४।३६। कर्मैव कार्मणम्। वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः।

२१०५। औषधेरजातौ।५।४।३७। स्वार्थेऽण्। औषधं पिबति। 'अजातौ' किम्। ओषधयः क्षेत्रे रूढाः।

२१०६। प्रज्ञादिभ्यश्च।५।४।३८। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। दैवतः। बान्धवः।

२१०७। मृदस्तिकन्।५।४।३९। मृदेव मृत्तिका।

२१०८। सस्नौ प्रशंसायाम्।५।४।४०। रूपपोऽपवादः। प्रशस्ता मृन्मृत्सा–मृत्स्ना। उत्तरसूत्रे 'अन्यतरस्याम्' ग्रहणान्नित्योऽयम्।

२१०९। बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्।५।४।४२। बहूनि ददाति बहुशः। अल्पानि अल्पशः। 'बह्वल्पार्थान्मङ्गलामङ्गलवचनम्' (वा ३३३८)। नेह। बहूनि ददात्यनिष्टेषु। अल्पं ददात्याभ्युदयिकेषु।

२११०। संख्यैकवचनाच्च वीप्सायाम्।५।४।४३। द्वौ द्वौ ददाति द्विशः। माषं माषं माषशः। प्रस्थशः। परिमाणशब्दा वृत्ताविकार्था एव। 'संख्यैकवचनात्' किम्। घटं घटं ददाति। 'वीप्सायाम्' किम्। द्वौ ददाति। 'कारकात्' इत्येव। द्वयोर्द्वयोः स्वामी।

२१११। प्रतियोगे पञ्चम्यास्तसिः।५।४।४४। प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात्। प्रद्युम्नः कृष्णतः प्रति। 'आद्यादिभ्य उपसंख्यानम्' (वा ३३३९)। आदौ आदितः। मध्यतः। अन्ततः। पृष्ठतः। पार्श्वतः। आकृतिगणोऽयम्। स्वरेण स्वरतः। वर्णतः।

२११२। अपादाने चाहीयरुहोः।५।४।४५। अपादाने या पञ्चमी तदन्तात्तसिः स्यात्। ग्रामादागच्छति। ग्रामतः। 'अहीयरुहोः' किम्। स्वर्गाद्धीयते। पर्वतादवरोहति।

२११३। अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः।५।४।४६। अकर्तरि तृतीयान्ताद्वा तसिः स्यात्। अतिक्रम्य ग्रहोऽतिग्रहः। चारित्रेणातिगृह्यते। चारित्रतोऽतिगृह्यते। चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः। अव्यथनमचलनम्। वृत्तेन न व्यथते। वृत्ततो न व्यथते। वृत्तेन न चलतीत्यर्थः। क्षेपे। वृत्तेन क्षिप्तः। वृत्ततः क्षिप्तः। वृत्तेन निन्दित इत्यर्थः। 'अकर्तरि' इति किम्। देवदत्तेन क्षिप्तः।

२११४। हीयमानपापयोगाच्च।५।४।४७। हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः। वृत्तेन हीयते। वृत्तेन पापः। वृत्ततः। क्षेपस्याविवक्षायामिदम्। क्षेपे तु पूर्वेण सिद्धम्। 'अकर्तरि' किम्। देवदत्तेन हीयते।

२११५। षष्ठ्या व्याश्रये।५।४।४८। षष्ठ्यन्ताद्वा तसिः स्यान्नानापक्षसमाश्रये।

देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य कर्णस्य पक्ष इत्यर्थः । 'अ
किम् । वृक्षस्य शाखा ।

२११६ । रोगाच्चापनयने । ५ । ४ । ४९ । रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चि
याम् । प्रवाहिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः । 'अपनयने' किम् । प्रवाहिका
प्रकोपनं करोति ।

२११७ । कृभ्वस्तियोगे संपद्यकर्तरि च्विः । ५ । ४ । ५० । 'अभूततद्भाव
वक्तव्यम्' (वा ३३४०) । विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात
च्विर्वा स्यात्करोत्यादिभिर्योगे ।

२११८ । अस्य च्वौ । ७ । ४ । ३२ । अवर्णस्य ईत्स्यात् च्वौ । च्वेर्लोपः । च्व
त्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णी करोति । ब्रह्मी भवति ।
स्यात् । 'अव्ययस्य च्वावीत्वं नेति वाच्यम्' (वा ५०५२) । दोषाभूतमहः । दिवा
रात्रिः' । एतच्च 'अव्ययीभावश्च' (सू ४५२) इति सूत्रे भाष्य उक्तम् ।

२११९ । क्यच्च्व्योश्च । ६ । ४ । १५२ । हलः परस्यापत्ययकारस्य लोपः स्या
च्वौ च परतः । गार्गी भवति ।

२१२० । च्वौ च । ७ । ४ । २६ । च्वौ परे पूर्वस्य दीर्घः स्यात् । शुची भवति
स्यात् । 'अव्ययस्य दीर्घत्वं न' इति केचित् । तन्निर्मूलम् । 'स्वस्ति स्यात्' इति तु
विभाषया च्वेरभावात्सिद्धम् । 'स्वस्ती स्यात्' इत्यपि पक्षे स्यादिति चेदस्तु । यदि ने
तर्ह्यनभिधानाच्च्विरेव नोत्पद्यत इत्यस्तु । 'रीङृतः' (सू १२३४) । मात्री करोति ।

२१२१ । अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च । ५ । ४ । ५१ । एषां लोपः स्या
अरू करोति । उन्मनी स्यात् । उच्चक्षू करोति । विचेती करोति । विरही क
विरजी करोति ।

२१२२ । विभाषा साति कार्त्स्न्ये । ५ । ४ । ५२ । च्विविषये सातिर्वा स्यात्सा

२१२३ । सात्पदाद्योः । ८ । ३ । १११ । सस्य षत्वं न स्यात् । दधि सिञ्चति ।
शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । अग्नी भवति । महाविभाषया वाक्यमपि । 'कार्त्स्न्ये'
एकदेशेन शुक्ली भवति पटः ।

२१२४ । अभिविधौ संपदा च । ५ । ४ । ५३ । संपदा कृभ्वस्तिभिश्च योगे
स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्निसात्संपद्यते अ
वति शस्त्रम् । अग्नी भवति । जलसात्संपद्यते जली भवति लवणम् । 'एकस्या व्यक्तेः
वयवावच्छेदेनान्यथाभावः कार्त्स्न्यम्' । 'बहूनां व्यक्तीनां किंचिदवयवावच्छेदेना
त्वभिविधिः' ।

२१२५ । तदधीनवचने । ५ । ४ । ५४ । सातिः स्यात्कृभ्वस्तिभिः संपदा च
राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ।

२१२६ । देये त्रा च । ५ । ४ । ५५ तदधीने देये त्रा स्यात्सातिश्च कृभ्वा

१. भाष्येष्टिभूतम् ।

विप्राधीनं देयं करोति विप्रत्रा करोति। विप्रत्रा संपद्यते। पक्षे विप्रसात्करोति। 'देये' किम्। राजसाद्भवति राष्ट्रम्।

२१२७। देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्। ५। ४। ५६। एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात्। देवत्रा वन्दे रमे वा। बहुलोक्तेरन्यत्रापि। बहुत्रा जीवतो मनः।

२१२८। अव्यक्तानुकरणाद्व्यजवरार्धादनितौ डाच्। ५। ४। ५७। 'द्व्यच्' अवरं न्यूनं, न तु ततो न्यूनम् 'अनेकाच्' इति यावत्तादृशमर्धं यस्य तस्माड्डाच्स्यात्कृभ्वस्तिभियोगे। 'डाचि विवक्षिते द्वे बहुलम्' (वा ४६९७)। 'नित्यमाम्रेडिते डाचीति वक्तव्यम्' (वा ३६३८)। डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात्। इति तकारपकारयोः पकारः। पटपटा करोति। 'अव्यक्तानुकरणात्' किम्। ईषत्करोति। 'द्व्यजवरार्धात्' किम्। श्रत्करोति। 'अवर-' इति किम्। खरटखरटा करोति। त्रपटत्रपटाकरोति। 'अनेकाचः' इत्येव सूत्रयितुमुचितम्। एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम्। 'अनितौ' किम्। पटिति करोति।

२१२९। कृञो द्वितीयतृतीयशम्बबीजात्कृषौ। ५। ४। ५८। द्वितीयादिभ्यो डाच्स्यात्कृञ एव योगे कर्षणेऽर्थे। बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम्। द्वितीयं तृतीयं कर्षणं करोति द्वितीया करोति। तृतीया करोति। शम्बशब्दः प्रतिलोमे। अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बा करोति। बीजेन सह कर्षति बीजा करोति।

२१३०। संख्यायाश्च गुणान्तायाः। ५। ४। ५९। कृञो योगे कृषौ डाच्स्यात्। द्विगुणा करोति क्षेत्रम्। क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः।

२१३१। समयाच्च यापनायाम्। ५। ४। ६०। 'कृषौ' इति निवृत्तम्। कृञो योगे डाच्स्यात्। समया करोति। कालं यापयतीत्यर्थः।

२१३२। सपत्त्रनिष्पत्त्रादतिव्यथने। ५। ४। ६१। सपत्त्रा करोति मृगम्। सपुङ्खशरप्रवेशेन सपत्त्रं करोतीत्यर्थः। निष्पत्त्रा करोति। सपुङ्खस्य शरस्यापरपार्श्वे निर्गमनान्निष्पत्त्रं करोतीत्यर्थः। 'अतिव्यथने' किम्। सपत्त्रं निष्पत्त्रं वा करोति भूतलम्।

२१३३। निष्कुलान्निष्कोषणे। ५। ४। ६२। निष्कुला करोति दाडिमम्। निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच्।

२१३४। सुखप्रियादानुलोम्ये। ५। ४। ६३। सुखा करोति प्रिया करोति गुरुम्। अनुकूलाचरणेनानन्दयतीत्यर्थः।

२१३५। दुःखात्प्रातिलोम्ये। ५। ४। ६४। दुःखा करोति। स्वामिनं पीडयतीत्यर्थः।

२१३६। शूलात्पाके। ५। ४। ६५। शूला करोति मांसम्। शूलेन पचतीत्यर्थः।

२१३७। सत्यादशपथे। ५। ४। ६६। सत्या करोति भाण्डं वणिक्। क्रेतव्यमिति तथ्यं करोतीत्यर्थः। शपथे तु सत्यं करोति विप्रः।

२१३८। मद्रात्परिवापणे। ५। ४। ६७। मद्रशब्दो मङ्गलार्थः। परिवापणं मुण्डनम्।

भद्रा करोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः । 'भद्राच्चेति वक्तव्यम्' (वा ३३…) भद्रा करोति । अर्थः प्राग्वत् । 'परिवापणे' किम् । भद्रं करोति ।

इति तद्धिततद्राजप्रकरणम् ।

अथ द्विरुक्तप्रकरणम् ।

२१३९ । सर्वस्य द्वे । ८ । १ । १ । इत्यधिकृत्य ।

२१४० । नित्यवीप्सयोः । ८ । १ । ४ । आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य … चनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । … भुक्त्वा । वीप्सायाम् । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ।

२१४१ । परेर्वर्जने । ८ । १ । ५ । परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परि… त्यर्थः । 'परेर्वर्जने वावचनम्' । (वा ४६८३) । परि वङ्गेभ्यः ।

२१४२ । उपर्यध्यधसः सामीप्ये । ८ । १ । ७ । उपर्युपरि ग्रामम् । ग्रामस्यो… ष्टात्समीपे देश इत्यर्थः । अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । … ऽधो लोकम् । लोकस्याधस्तात्समीपे देश इत्यर्थः ।

२१४३ । वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु । ८ । १ । … असूयायाम् । सुन्दर सुन्दर वृथा ते सौन्दर्यम् । संमतौ । देव देव वन्द्योऽसि । … दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि । कुत्सने । धानुष्क धानुष्क वृथा ते धनुः । भर्… चोर चोर घातयिष्यामि त्वाम् ।

२१४४ । एकं बहुव्रीहिवत् । ८ । १ । ९ । द्विरुक्त एकशब्दो बहुव्रीहिवत्स्यात् … सुब्लोपपुंवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रा… दिकत्वात्समुदायात्सुप् । एकैकयाहुत्या । इह पूर्वभागे पुंवद्भावाद्विग्रहे विशेषः । 'न बहु…' (सू २२२) इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहे… नामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहु… ऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ।

२१४५ । आबाधे च । ८ । १ । १० । पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च… गतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह पुंवद्भावः…

२१४६ । कर्मधारयवदुत्तरेषु । ८ । १ । ११ । इह उत्तरेषु द्विर्वचनेषु कर्मधार… त्कार्यम् । प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि (वा ४६८९) ।

२१४७ । प्रकारे गुणवचनस्य । ८ । १ । १२ । सादृश्ये द्योत्ये गुणवचनस्य … स्तस्तच्च कर्मधारयवत् । 'कर्मधारयवदुत्तरेषु–' (सू २१४६) इत्यधिकारात् । तेन … भागस्य पुंवद्भावः 'समासस्य' (सू ३७३४) इत्यन्तोदात्तत्वं च । पटुपट्वी । प… पटुसदृशः । ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचि… गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः । 'आनुपूर्व्ये द्वे वाच्ये' (वा ४६९२) । मूले … स्थूलः । 'संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः' (वा ५०५६) । सर्पं सर्पं बु…

---

१. अत्र च 'चापले च' (वा ४६९४) इति वार्तिके, 'नचावश्यं द्वे एव । यावद्भिः … गम्यते तावन्तः प्रयोक्तव्याः' इति भाष्यं च मानम् ।

बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वा ४६९९) लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (सू २१४०) इति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समुच्चित्य द्योतकतां लब्धुं वा । 'कर्मव्यतिहारे सर्वनाम्नो वाच्ये समासवच्च बहुलम्' (वा ४७००) । बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य तु नित्यम् । 'असमासवद्भावे पूर्वपदस्थस्य सुपः सुर्वक्तव्यः' (वा ४७००) । अन्योन्यं विप्रा नमन्ति । अन्योन्यौ । अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि - अन्योन्येषां पुष्करैरामृशन्ते' इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि । 'स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः (वा ४७०१) । अन्योन्याम्–अन्योन्यम् । परस्पराम्–परस्परम् । इतरेतराम्–इतरेतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः । अत्र केचित् । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामादेशमाहुः ।

दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः ।
समासे सोरलुक्चेति सिद्धं बाहुलकाश्रयम् ॥

तथाहि । अन्योन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्तः । न च 'सर्वनाम्नो वृत्तिमात्रे–(वा) इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । न च द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः प्रैक्षत कातराक्षी सा सा' इत्यादावतिप्रसङ्गात् । 'अन्योन्यमितरेतरम्' इत्यत्र च 'अद्ड्डतरादिभ्यः–' (सू ३१९) इत्यद्ड् प्राप्तः । 'अन्योन्यसंसक्तमहस्त्रियामम्,' 'अन्योन्याश्रयः,' 'परस्पराक्षिसादृश्यम्' । 'अदृष्टपरस्परैः' इत्यादौ सोर्लुक्च प्राप्तः सर्वं बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणम् 'स्त्रियाम्' (सू ४५२) इति सूत्रे 'अन्योन्यसंश्रयम्' त्वेतदिति भाष्यं चात्र प्रमाणमिति ।

२१४८ । अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । ८ । १ । १३ । प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ।

२१४९ । यथास्वे यथायथम् । ८ । १ । १४ । 'यथास्वम्' इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता यथास्वभावमित्यर्थः । यथात्मीयमिति वा ।

२१५० । द्वंद्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु । ८।१। १५ द्विशब्दस्य द्विर्वचनं पूर्वपदस्याम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वंद्वशब्दस्य वाच्यम् । इतर विषयभूताः । द्वंद्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः आचतुरं हीमे पशवो द्वंद्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति पौत्रेण प्रपौत्रेणापीति मर्यादार्थः । व्युत्क्रमणं पृथगवस्थानम् । द्वंद्वं व्युत्क्रा-

न्ता द्विवर्गसंबन्धेन पृथगवस्थिताः । द्वंद्वं यज्ञपात्राणि प्रयुनक्ति । द्वंद्वं संकर्षणवासुदेवौ अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वंद्वं द्र इष्यते ।

इति द्विरुक्तप्रकरणम् ।

इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्धं समाप्तम् ।

॥ श्रीः ॥

वैयाकरणसिद्धान्तकौमुदी ।

श्रीत्राहन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् ।
तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम् ॥
पूर्वार्धे कथितास्तुर्यपञ्चमाध्यायवर्तिनः ।
प्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः ॥

अथ तिङन्तभ्वादिप्रकरणम् ।

तत्रादौ दश लकाराः प्रदर्श्यन्ते । लट् । लिट् । लुट् । लृट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । लृङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ।

२१५१ । वर्तमाने लट् । ३ । २ । १२३ । वर्तमानाक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ।

२१५२ । लः कर्मणि च भावे चाकर्मकेभ्यः । ३ । ४ । ६९ । लकाराः सकर्मकेभ्यः कर्माणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ।

२१५३ । लस्य । ३ । ४ । ७७ । अधिकारोऽयम् ।

२१५४ । तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । ३ । ४ । ७८ । एतेऽष्टादश लादेशाः स्युः ।

२१५५ । लः परस्मैपदम् । १ । ४ । ९९ । लादेशाः परस्मैपदसंज्ञाः स्युः ।

२१५६ । तङानावात्मनेपदम् । १ । ४ । १०० । तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ।

२१५७ । अनुदात्तङित आत्मनेपदम् । १ । ३ । १२ । अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थान आत्मनेपदं स्यात् ।

२१५८ । स्वरितञितः कर्त्रभिप्राये क्रियाफले । १ । ३ । ७२ । स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ।

२१५९ । शेषात्कर्तरि परस्मैपदम् । १ । ३ । ७८ । आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ।

२१६० । तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः । १ । ४ । १०१ । तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ।

२१६१ । तान्येकवचनद्विवचनबहुवचनान्येकशः । १ । ४ । १०२ । लब्धप्रथ...मादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ।

२१६२ । युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः । १ । ४ । १०५ । तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ।

२१६३ । प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च । १ । ४ । १०६ । मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स च चैकार्थस्य वाचकः स्यात् ।

२१६४ । अस्मद्युत्तमः । १ । ४ । १०७ । तथाभूतेऽस्मद्युत्तमः स्यात् ।

२१६५ । शेषे प्रथमः । १ । ४ । १०८ । मध्यमोत्तमयोरविषये प्रथमः स्यात् । 'भू १ सत्तायाम्' । कर्तृविवक्षायां भू ति इति स्थिते ।

२१६६ । तिङ्शित्सार्वधातुकम् । ३ । ४ । ११३ । तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ।

२१६७ । कर्तरि शप् । ३ । १ । ६८ । कर्त्रर्थे सार्वधातुके परे धातोः शप्स्यात् शपावितौ ।

२१६८ । सार्वधातुकार्धधातुकयोः । ७ । ३ । ८४ । अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ।

२१६९ । झोऽन्तः । ७ । १ । ३ । प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । 'अतो गुणे' (सू. १९१) भवन्ति । भवसि । भवथः । भवथ ।

२१७० । अतो दीर्घो यञि । ७ । ३ । १०१ । अतोऽङ्गस्य दीर्घः स्याद्यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि युवां भवथः । यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्ये ओदनं भोक्ष्यस इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । 'युष्मद्युपपदे' (सू. २१६२) इत्याद्यनुवर्तते तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः । 'प्रहासे' किम् । यथार्थकथने मा भूत् । एहि मन्यसे ओदनं भोक्ष्यै इति भुक्तः सोऽतिथिभिरित्यादि ।

२१७१ । परोक्षे लिट् । ३ । २ । ११५ । भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ।

२१७२ । लिट् च । ३ । ४ । ११५ । लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ।

२१७३ । परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । ३ । ४ । ८२ । लिटस्तिबादीनां नवानां णलादयो नव स्युः । 'भू' 'अ' इति स्थिते ।

२१७४ । भुवो वुग्लुङ्लिटोः । ६ । ४ । ८८ । भुवो वुगागमः स्यात् । लुङ्लिटोरचि । नित्यत्वाद्वुग्गुणवृद्धी बाधते ।

२१७५ । एकाचो द्वे प्रथमस्य । ६ । १ । १ ।

२१७६। अजादेर्द्वितीयस्य। ६।१।२। इत्यधिकृत्य।

२१७७। लिटि धातोरनभ्यासस्य। ६।१।८। लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य। 'भूव्' 'भव्' 'अ' इति स्थिते।

२१७८। पूर्वोऽभ्यासः। ६।१।४। अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्।

२१७९। हलादिः शेषः। ७।४।६०। अभ्यासस्यादिर्हल्शिष्यतेऽन्ये हलो लुप्यन्ते। इति वलोपः।

२१८०। ह्रस्वः। ७।४।५९। अभ्यासस्याचो ह्रस्वः स्यात्।

२१८१। भवतेरः। ७।४।७३। भवतेरभ्यासोकारस्य 'अः' स्याल्लिटि।

२१८२। अभ्यासे चर्च। ८।४।५४। अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः। खयां चरः। तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात्।

२१८३। असिद्धवदत्राभात्। ६।४।२२। इत ऊर्ध्वमापादपरिसमाप्तेराभीयम्। समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात्। इति वुकोऽसिद्धत्वादुवङि प्राप्ते। 'वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ' (वा ४०६२)। बभूव। बभूवतुः। बभूवुः।

२१८४। आर्धधातुकस्येड्वलादेः। ७।२।३५। वलादेरार्धधातुकस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम।

२१८५। अनद्यतने लुट्। ३।३।१५। भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात्।

२१८६। स्यतासी ऌलुटोः। ३।१।३३। 'ऌ' इति लृङ्लृटोर्ग्रहणम्। धातोः स्यतासी एतौ प्रत्ययौ स्तो ऌलुटोः परतः। शबाद्यपवादः।

२१८७। आर्धधातुकं शेषः। ३।४।११४। तिङ्शिद्भ्योऽन्यो धात्वधिकारोक्तः प्रत्यय एतत्संज्ञः स्यात्। इट्।

२१८८। लुटः प्रथमस्य डारौरसः। २।४।८५। 'डा' 'रौ' 'रस्' एते क्रमात्स्युः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः।

२१८९। पुगन्तलघूपधस्य च। ७।३।८६। पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः। येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्। तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः। 'भवित्' 'आ' अत्रेको गुणे प्राप्ते।

२१९०। दीधीवेवीटाम्। १।१।६। दीधीवेव्योरिटश्च गुणवृद्धी न स्तः। भविता।

२१९१। तासस्त्योर्लोपः। ७।४।५०। तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे।

२१९२। रि च। ७।४।५१। रादौ प्रत्यये प्राग्वत्। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः।

२१९३। लृट् शेषे च। ३।३।१३। भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च। स्य इट्। भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि। भविष्यथः। भविष्यथ। भविष्यामि। भविष्यावः। भविष्यामः।

२१९४। लोट् च। ३।३।१६२। विध्यादिष्वर्थेषु धातोर्लोट् स्यात्।

२१९५। आशिषि लिङ्लोटौ। ३।३।१७३।

२१९६ । एरुः । ३ । ४ । ८६ । लोट इकारस्य उः स्यात् । भवतु ।

२१९७ । तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् । ७ । १ । ३५ । आशिषि तुह्योस्ता स्यात् । अनेकाल्त्वात्सर्वादेशः । यद्यपि 'ङिच्च' (सू ४३) इत्ययमपवादः, तथाप्यनन्त्ये त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङ्कारे ङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ।

२१९८ । लोटो लङ्वत् । ३ । ४ । ८५ । लोटो लङ इव कार्यं स्यात् । तेन ताम सलोपश्च । तथा हि ।

२१९९ । तस्थस्थमिपां तांतंतामः । ३ । ४ । १०१ । ङितश्चतुर्णामेषां तामादयः क्रमा

२२०० । नित्यं ङितः । ३ । ४ । ९९ । सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः स्या 'अलोऽन्त्यस्य' (सू ४२) इति सस्य लोपः । भवताम् । भवन्तु ।

२२०१ । सेर्ह्यपिच्च । ३ । ४ । ८७ । लोटः सेर्हिः स्यात्सोऽपिच्च ।

२२०२ । अतो हेः । ६ । ४ । १०५ । अतः परस्य हेर्लुक्स्यात् । भव-भवतात् । भवत भवत ।

२२०३ । मेर्निः । ३ । ४ । ८९ । लोटो मेर्निः स्यात् ।

२२०४ । आडुत्तमस्य पिच्च । ३ । ४ । ९२ । लोडुत्तमस्याडागमः स्यात्स पिच्च । हि रुत्वं न । इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ।

२२०५ । अनद्यतने लङ् । ३ । २ । १११ । अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्या

२२०६ । लुङ्लङ्लृङ्क्ष्वडुदात्तः । ६ । ४ । ७१ । एषु परेष्वङ्गस्याडागमः स चोदात्तः ।

२२०७ । इतश्च । ३ । ४ । १०० । ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ।

२२०८ । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् । ३ । ३ । १६१ । ए र्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणम्, भृत्यादेर्निकृष्टस्य प्रवर्तनम् । नि न्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचा नुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । 'प्रवर्तनायां लिङ्' इत्येव सुवचम् । चतुर्णां गुपादानं प्रपञ्चार्थम् ।

२२०९ । यासुट् परस्मैपदेषूदात्तो ङिच्च । ३ । ४ । १०३ । लिङः परस्मैपदानां डागमः स्यात्स चोदात्तो ङिच्च । ङित्वोक्तेर्ज्ञायते 'क्वचिदनुबन्धकार्येऽप्यनल्विधि प्रतिषेधः' इति । आदेशस्य शानचः शित्त्वमपीह लिङ्गम् ।

२२१० । सुट् तिथोः । ३ । ४ । १०७ । लिङस्तकारथकारयोः सुट् स्यात् । सुटा ट् न बाध्यते । लिङो यासुट्, तकारथकारयोः सुडिति विषयभेदात् ।

२२११ । लिङः सलोपोऽनन्त्यस्य । ७ । २ । ७९ । सार्वधातुकलिङोऽनन्त्यस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु त्मनेपदे ।

२२१२ । अतो येयः । ७ । २ । ८० । अतः परस्य सार्वधातुकावयवस्य 'या' इत्यस्य 'इय' स्यात् । गुणः । यलोपः । भवेत् । 'सार्वधातुक–' इति किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ।

२२१३ । झेर्जुस् । ३ । ४ । १०८ । लिङो झेर्जुस् स्यात् । ज इत् ।

२२१४ । उस्यपदान्तात् । ६ । १ । ९६ । अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्च 'अतो येयः'(सू२२१२) इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि 'यास' इत्येतस्य 'इय्' इति व्याख्येयम् । एवं च सलोपस्यापवाद इय् । 'अतो येयः' (सू२२१२) इत्यत्र तु संधिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ।

२२१५ । लिङाशिषि । ३ । ४ । ११६ । आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ।

२२१६ । किदाशिषि । ३ । ४ । १०४ । आशिषि लिङो यासुट् कित्स्यात् । 'स्कोः–' (सू ३८०) इति सलोपः ।

२२१७ । क्ङिति च । १ । १ । ५ । गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व ॥ भूयास्म ।

२२१८ । लुङ् । ३ । २ । ११० । भूतार्थवृत्तेर्धातोर्लुङ् स्यात् ।

२२१९ । माङि लुङ् । ३ । ३ । १७५ । सर्वलकारापवादः ।

२२२० । स्मोत्तरे लङ् च । ३ । ३ । १७६ । स्मोत्तरे माङि लङ् स्याल्लुङ् च ।

२२२१ । च्लि लुङि । ३ । १ । ४३ । शबाद्यपवादः ।

२२२२ । च्लेः सिच् । ३ । १ । ४४ । इचावितौ ।

२२२३ । गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २ । ४ । ७७ । एभ्यः सिचो लुक्स्यात् । गापाविहेणादेशपिबती गृह्येते ।

२२२४ । भूसुवोस्तिङि । ७ । ३ । ८८ । 'भू' 'सू' एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ।

२२२५ । अस्तिसिचोऽपृक्ते । ७ । ३ । ९६ । 'सिच्' च 'अस्' चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तहल ईडागमः स्यात् । इति ईट् न । इह सिचो लुप्तत्वात् । अभूत् । 'हलः' किम् । ऐधिषि । 'अपृक्तस्य' इति किम् । ऐधिष्ट । अभूताम् ।

२२२६ । सिजभ्यस्तविदिभ्यश्च । ३ । ४ । १०९ । सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ।

२२२७ । आतः । ३ । ४ । ११० । सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ।

२२२८ । न माङ्योगे । ६ । ४ । ७४ । अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ।

२२२९ । लिङ्निमित्ते लृङ् क्रियातिपत्तौ । ३ । ३ । १३९ । हेतुहेतुमद्भावादि लिङ्-

मित्तं तत्र भविष्यत्यर्थे लृङ् स्यात्क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभ-
विष्यताम् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभवि-
ष्याव । अभविष्याम ।

२२३० । ते प्राग्धातोः । १ । ४ । ८० । ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयो-
क्तव्याः ।

२२३१ । आनि लोट् । ८ । ४ । १६ । उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्या-
न्यस्य नस्य णः स्यात् । प्रभवाणि । 'दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्त-
(वा ११३८) । दुःस्थितिः । दुर्भवानि । 'अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गत्वं वाच्य-
(वा ११४१) । अन्तर्धा । अन्तर्धिः । अन्तर्भवाणि ।

२२३२ । शेषे विभाषाकखादावषान्त उपदेशे । ८ । ४ । १८ । उपदेशे क-
खादिषान्तवर्जे गदनदादेरन्यस्मिन्धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णः
स्यात् । प्रणिभवति-प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम्-

'संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥'

इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपस-
र्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति ।
उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च—

'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ॥'

इति । 'एध २ वृद्धौ' । कत्थन्ताः षट्त्रिंशदनुदात्तेतः ।

२२३३ । टित आत्मनेपदानां टेरे । ३ । ४ । ७९ । टितो लस्यात्मनेपदानां टेरेत्वं
स्यात् । एधते ।

२२३४ । सार्वधातुकमपित् । १ । २ । ४ । अपित्सार्वधातुकं ङिद्वत्स्यात् ।

२२३५ । आतो ङितः । ७ । २ । ८१ । अतः परस्य ङितामाकारस्य इय्स्यात् । ए-
धेते । एधन्ते ।

२२३६ । थासः से । ३ । ४ । ८० । टितो लस्य थासः से स्यात् । एधसे । एधेथे ।
एधध्वे । 'अतो गुणे' (सू १९१) । एधे । एधावहे । एधामहे ।

२२३७ । इजादेश्च गुरुमतोऽनृच्छः । ३ । १ । ३६ । इजादिर्यो धातुर्गुरुमानृच्छत्य-
न्यस्तत आम्स्याल्लिटि । 'आमो मकारस्य नेत्त्वम्' । आस्कासोराम्विधानाज्ज्ञापकात् ।

२२३८ । आमः । २ । ४ । ८१ । आमः परस्य लुक्स्यात् ।

२२३९ । कृञ्चानुप्रयुज्यते लिटि । ३ । १ । ४० । आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्र-
युज्यन्ते । 'आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य' (सू २२४०) इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्र-
योगोऽन्यस्यापीति ज्ञायते । तेन 'कृभ्वस्तियोगे-' (सू २११७) इत्यतः 'कृञो द्वि-'
(सू २१२९) इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचि-

प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ।

२२४० । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य । १ । ३ । ६३ । आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् । इह 'पूर्ववत्' इत्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ।

२२४१ । लिटस्तझयोरेशिरेच् । ३ । ४ । ८१ । लिडादेशयोस्तझयोः 'एश्' 'इरेच्' एतौ स्तः । एकारोच्चारणं ज्ञापकं 'तङादेशानां टेरेत्वं न' इति । तेन डारौरसां न । 'कृ' 'ए' इति स्थिते ।

२२४२ । असंयोगाल्लिट्कित् । १ । २ । ५ । असंयोगात्परोऽपि लिट्कित्स्यात् । 'क्ङिति च' (सू २२१७) इति निषेधात् 'सार्वधातुकार्धधातुकयोः' (सू २१६८) इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ।

२२४३ । द्विर्वचनेऽचि । १ । १ । ५९ । द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ।

२२४४ । उरत् । ७ । ४ । ६६ । अभ्यासऋवर्णस्यात्स्यात्प्रत्यये परे । रपरत्वम् । 'हलादिः शेषः' (सू २१७९) । 'प्रत्यये' किम् । वव्रश्च ।

२२४५ । कुहोश्चुः । ७ । ४ । ६२ । अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ।

२२४६ । एकाच उपदेशेऽनुदात्तात् । ७ । २ । १० । उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येड् न स्यात् । 'उपदेशे' इत्युभयान्वयि । 'एकाचः' इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि—

'श्तिपा शपानुबन्धेन निर्दिष्टं यद्गणेन च ।
यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥' (प १३२)

इति । एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । 'अचः' इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्कत्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ।

२२४७ । इणः षीध्वंलुङ्लिटां धोऽङ्गात् । ८ । ३ । ७८ । इण्णन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य मूर्धन्यः स्यात् । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे । एधांचकृमहे । एधांबभूव । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि 'कृञ्चानुप्रयुज्यते' इति 'कृभु—' इति वा ब्रूयात् ।

२२४८ । अत आदेः । ७ । ४ । ७० । अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवादः । एधामास । एधामासतुरित्यादि । एधिता । एधितारौ । एधितारः । एधितासे । एधितासाथे ।

२२४९ । धि च । ८ । २ । २५ । धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ।

२२५० । ह एति । ७ । ४ । ५२ । तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । ए-

एधितास्वहे । एधितास्महे । एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ।

२२५१ । आमेतः । ३ । ४ । ९० । लोट एकारस्यामस्यात् । एधताम् । एधेताम् । एधन्ताम् ।

२२५२ । सवाभ्यां वामौ । ३ । ४ । ९१ । सवाभ्यां परस्य लोडेतः क्रमात् व 'अम्' एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ।

२२५३ । एत ऐ । ३ । ४ । ९३ । लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ।

२२५४ । आडजादीनाम् । ६ । ४ । ७२ । अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः । 'आटश्च' (सू २६९) । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ।

२२५५ । लिङः सीयुट् । ३ । ४ । १०२ । लिङात्मनेपदस्य सीयुडागमः स्यात् । सलोपः । एधेत । एधेयाताम् ।

२२५६ । झस्य रन् । ३ । ४ । १०५ । लिङो झस्य रन्स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ।

२२५७ । इटोऽत् । ३ । ४ । १०६ । लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि । आशीर्लिङि आर्धधातुकत्वाल्लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट । एधिषीयास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ।

२२५८ । आत्मनेपदेष्वनतः । ७ । १ । ५ । अनकारात्परस्यात्मनेपदेषु झस्य 'अत्' इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् । 'इणः षीध्वंलुङ्लिटां धोऽङ्गात्' (सू २२४७) । ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यत इति मते तु । ऐधिध्वम् । ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्धलादेरिट् । प्रसङ्गादनुदात्ताः संगृह्यन्ते ।

ऊद्दन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः ।
वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥
शक्लृपच्मुचिरिच्वच्विच्सिच्प्रच्छित्यज्निजिर्भजः ।
भञ्जभुज्भ्रस्ज्मस्जियज्युजरुज्रञ्जविजिर्स्वञ्जिसञ्जसृजः ॥
अद्क्षुद्खिद्छिद्तुदिनुदः पद्यभिद्विद्यतिर्विनद् ।
शद्सदी स्विद्यति स्कन्दिहदी क्रुध्क्षुधिबुध्यती ॥
बन्धिर्युधिरुधीराधिव्यध्शुधः साधिसिध्यती ।
मन्यहन्नाप्क्षिप्छुपितप्तिपस्तृप्यतिदृप्यती ॥
लिप्लुप्वप्शप्स्वप्सृपियभ्रभ्लभ्गम्नम्यमो रमिः ।
क्रुशिर्दंशिदिशी दृश्मृश्रिशरुश्लिश्विश्स्पृशः कृषिः ॥

त्विषतुषद्विषदुषपुष्यपिषविषशिषशुषश्लिष्यतयो घसिः ।
वसतिर्दहदिहिदुहो नहमिहरुहलिह् वहिस्तथा ॥
अनुदात्ता हलन्तेषु धातवो ह्यधिकं शतम् ।
तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥
तृप्दृपी तौ वारयितुं श्यना निर्देश आदृतः ।

किं च ।

स्विद्यपचौ सिध्यबुध्यौ मन्यपुष्यश्लिषः श्यना ॥
वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ।
निजिर्विजिर्शक्लृ इति सानुबन्धा अमी तथा ॥
विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ।
व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥
रञ्जिमस्जी अदिपदी नुद् क्षुध् शुषिपुषी शिषिः ।
भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥

'स्पर्ध ३ संघर्षे' । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ।

२२५९ । शर्पूर्वाः खयः । ७ । ४ । ६१ । अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । 'हलादिः शेषः' (सू २१७९) इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत । 'गाधृ ४ प्रतिष्ठालिप्सयोर्ग्रन्थे च' । गाधते । जगाधे । 'बाधृ ५ लोडने' । लोडनं प्रतिघातः । बाधते । 'नाथृ ६ नाधृ ७ याच्ञोपतापैश्वर्याशीःषु' । 'आशिषि नाथ इति वाच्यम्' (वा ९१०) । अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते । 'दध ८ धारणे' । दधते ।

२२६० । अत एकहल्मध्येऽनादेशादेर्लिटि । ६ । ४ । १२० । लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्यैकारः स्यादभ्यासलोपश्च किति लिटि ।

२२६१ । थलि च सेटि । ६ । ४ । १२१ । प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते । शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । 'अतः' किम् । दिदिवतुः । 'तपरः' किम् । ररासे । 'एक–' इत्यादि किम् । तत्सरतुः । 'अनादेशादेः' किम् । चकणतुः । लिट आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे । 'स्कुदि ९ आप्रवणे' । आप्रवणमुत्प्लवनमुद्धरणं च ।

२२६२ । इदितो नुम्धातोः । ७ । १ । ५८ । स्कुन्दते । चुस्कुन्दे । 'श्विदि १० श्वैत्ये' । अकर्मकः । श्विन्दते । शिश्विन्दे । 'वदि ११ अभिवादनस्तुत्योः' । वन्दते । ववन्दे । 'भदि १२ कल्याणे सुखे च' । भन्दते । बभन्दे । 'मदि १३ स्तुतिमोदमदस्वप्नकान्तिगतिषु' । मन्दते । ममन्दे । 'स्पदि १४ किंचिच्चलने' । स्पन्दते । पस्पन्दे । 'क्लिदि १५ परिदेवने' । शोक इत्यर्थः । सकर्मकः । क्लिन्दते चैत्रम् । चिक्लिन्दे । 'मुद १६ हर्षे' । मोदते । 'दद १७ दाने' । ददते ।

२२६३ । न शसददवादिगुणानाम् । ६ । ४ । १२६ । शसेर्ददेर्वकारादीनां गुणशब्देन

भावितस्य च योऽकारस्तस्यैत्वाभ्यासलोपौ न । ददे । ददाते । ददिरे । 'ष्वद १८ आस्वादने'। अयमनुभवे सकर्मकः । रुचावकर्मकः ।

२२६४ । धात्वादेः षः सः । ६ । १ । ६४ । धातोरादेः षस्य सः स्यात् । 'सात्पदाद्योः' (सू २१२३) इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे । 'उर्द २० माने क्रीडायां च' ।

२२६५ । उपधायां च । ८ । २ । ७८ । धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते । ऊर्दांचक्रे । 'कुर्द २१ खुर्द २२ गुर्द २३ गुद २४ क्रीडायामेव'। कूर्दते । चुकूर्दे । खूर्दते । गूर्दते । गोदते । जुगुदे । 'षूद २५ क्षरणे' । सूदते । सुषूदे ।

'सेक्सृप्सृस्तृसृज्स्तृस्त्यान्ये दन्त्याजन्तसादयः ।

एकाचः षोपदेशाः ष्वष्क्स्विद्स्वद्स्वञ्जस्वपस्मिङः ॥' [इति भाष्यफलितार्थः]

दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपि । ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् । 'ह्राद २६ अव्यक्ते शब्दे' । ह्रादते । जह्रादे । 'ह्लादी २७ सुखे च' । चादव्यक्ते शब्दे । ह्लादते । 'स्वाद २८ आस्वादने' । स्वादते । 'पर्द २९ कुत्सिते शब्दे' । गुदरव इत्यर्थः । पर्दते । 'यती ३० प्रयत्ने' । यतते । येते । 'युतृ ३१ जुतृ ३२ भासने' । योतते । युयुते । जोतते । जुजुते । 'विथृ ३३ वेथृ ३४ याचने' । विविथे । विवेथे । 'श्रथि ३५ शैथिल्ये' । श्रन्थते । 'ग्रथि ३६ कौटिल्ये' । ग्रन्थते । 'कत्थ ३७ श्लाघायाम्' । कत्थते । एधादयोऽनुदात्तेतो गताः ।

अथाष्टात्रिंशत्तवर्गीयान्ताः परस्मैपदिनः । 'अत ३८ सातत्यगमने' । अतति । 'अत आदेः' (सू २२४८) आत । आततुः । आतुः । लुङि 'आनिस् ईत्' इति स्थिते ।

२२६६ । इट ईटि । ८ । २ । २८ । इटः परस्य सस्य लोपः स्यादीटि परे । 'सिज्लोप एकादेशे सिद्धो वाच्यः' (वा ४७७१) । आतीत् । आतिष्टाम् । आतिषुः ।

२२६७ । वदव्रजहलन्तस्याचः । ७ । २ । ३ । वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ।

२२६८ । नेटि । ७ । २ । ४ । इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । मा अतिष्टाम् । अतिषुः । 'चिती ३९ संज्ञाने' । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । 'च्युतिर् ४० आसेचने' । सेचनमार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च । 'इर इत्संज्ञा वाच्या' (वा ८३९) । च्योतति । चुच्योत ।

२२६९ । इरितो वा । ३ । १ । ५७ । इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत्-अच्योतीत् । 'श्च्युतिर् ४१ क्षरणे' । श्च्योतति । चुश्च्योत । अश्च्युतत्-अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति । 'मन्थ ४२ विलोडने' । विलोडनं प्रतीघातः । मन्थति । ममन्थ । यासुटः 'किदाशिषि' (सू २२१६) इति कित्त्वात् 'अनिदिताम्' (सू ४१५) इति नलोपः । मथ्यात् । 'कुथि ४३ पुथि ४४ लुथि ४५ माथि ४६ हिंसासंक्लेशनयोः' । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् । 'षिध ४७ गत्याम्' । सेधति । सिषेध । सेधिता । असेधीत् । 'सात्पदाद्योः' (सू २१२३) इति निषेधे प्राप्ते ।

२२७० । उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । ८ । ३ । । ६५ । उपसर्गस्थादिण्निमित्तादेषां सस्य षः स्यात् ।

२२७१ । सदिरप्रतेः । ८ । ३ । ६६ । प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ।

२२७२ । स्तन्भेः । ८ । ३ । ६७ । सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किं च 'अप्रतेः' इति नानुवर्तते । 'बाहुप्रतिष्टम्भविवृद्धमन्युः' इति ।

२२७३ । अवाच्चालम्बनाविदूर्ययोः । ८ । ३ । ६८ । अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ।

२२७४ । वेश्च स्वनो भोजने । ८ । ३ । ६९ । व्यवाभ्यां स्वनतः सस्य षः स्याद्भोजने ।

२२७५ । परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् । ८ । ३ । ७० । परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ।

२२७६ । प्राक्सितादड्व्यवायेऽपि । ८ । ३ । ६३ । '–सेवसित–' (सू २२७५) इत्यत्र सितशब्दात्प्राग्ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ।

२२७७ । स्थादिष्वभ्यासेन चाभ्यासस्य । ८ । ३ । ६४ । प्राक्सितात्स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ।

२२७८ । सेधतेर्गतौ । ८ । ३ । ११३ । गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति । 'षिधू ४८ शास्त्रे माङ्गल्ये च' । शास्त्रं शासनम् ।

२२७९ । स्वरतिसूतिसूयतिधूञूदितो वा । ७ । २ । ४४ । स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ।

२२८० । झषस्तथोर्धोऽधः । ८ । २ । ४० । झषः परयोस्तथोर्धः स्यान्न तु दधातेः जश्त्वम् । सिषेद्ध–सिषेधिथ । सेद्धा–सेधिता । सेत्स्यति–सेधिष्यति । असैत्सीत् ।

२२८१ । झलो झलि । ८ । २ । २६ । झलः परस्य सस्य लोपः स्याज्झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षेऽसेधीत् । असेधिष्टामित्यादि । 'खादृ ४९ भक्षणे' । ऋकार इत् । खादति । चखाद । 'खद ५० स्थैर्ये हिंसायां च' । चाद्भक्षणे । स्थैर्येऽकर्मकः । खदति ।

२२८२ । अत उपधायाः । ७ । २ । ११६ । उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ।

२२८३ । णलुत्तमो वा । ७ । १ । ९१ । उत्तमो णल्वा णित्स्यात् । चखाद–चखद ।

२२८४ । अतो हलादेर्लघोः । ७ । २ । ७ । हलादेर्लघोरकारस्येडादौ परस्मैपदे परे सिचि वृद्धिर्वा स्यात् । अखादीत्–अखदीत् । 'बद ५१ स्थैर्ये' । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद–बबद । अबादीत्–अबदीत् । 'गद ५२ व्यक्तायां वाचि' । गदति ।

२२८५ । नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । ८ । ४ । १७ । उपसर्गस्थान्निमित्तात्परस्य नेर्णः स्याद्गदादिषु । प्रणिगदति । जगाद । 'रद ५३ विलेखने' । विलेखनं भेदनम् । रराद । रेदतुः । 'णद ५४ अव्यक्ते शब्दे' ।

२२८६ । णो नः । ६ । १ । ६५ । धातोरादेर्णस्य नः स्यात् ।

'णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्द्नक्नॄनृतः' [इति भाष्यफलितम् ।]

नाट्टेर्दीर्घार्हस्य पर्युदासादट्टादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नृनन्धोश्च केचिन्नो
शतामाहुः ।

२२८७ । उपसर्गादसमासेऽपि णोपदेशस्य । ८ । ४ । १४ । उपसर्गस्थान्निमित्तात्
णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदति । 'अर्द ५५
याचने च' । 'अत आदेः' (सू २२४८) ।

२२८८ । तस्मान्नुड्द्विहलः । ७ । ४ । ७१ । द्विहलो धातोर्दीर्घीभूतादकारात्परस्य नुट्
स्यात् । आनर्द । आर्दीत् । 'नर्द ५६ गर्द ५७ शब्दे' । णोपदेशत्वाभावान्न णः । प्रनर्दति ।
गर्दति । जगर्द । 'तर्द ५८ हिंसायाम्' । तर्दति । 'कर्द ५९ कुत्सिते शब्दे' । कुक्षि
कौक्षे । कर्दति । 'खर्द ६० दंदशूके' । दंशहिंसादिरूपायां दंदशूकक्रियायामित्यर्थः । खर्दति ।
चखर्द । 'अति ६१ अदि ६२ बन्धने' । अन्तति । आनन्त । अन्दति । आनन्द । 'इदि
६३ परमैश्वर्ये' । इन्दति । इन्दांचकार । 'विदि ६४ अवयवे' । पवर्गतृतीयादिः । बिन्दति ।
अवयवं करोतीत्यर्थः । 'भिदि' इति पाठान्तरम् । 'गडि ६५ वदनैकदेशे' । गण्डति ।
'अन्तत्यादयः पञ्चैते न तिङ्विषया' इति काश्यपः । अन्ये तु तिङमपीच्छन्ति । 'णिदि
कुत्सायाम्' । निन्दति । प्रणिन्दति । 'टुनदि ६७ समृद्धौ' ।

२२८९ । आदिर्ञिटुडवः । १ । ३ । ५ । उपदेशे धातोराद्या एते इतः स्युः । नन्दति ।
इदित्त्वान्नलोपो न । नन्द्यात् । 'चदि ६८ आह्लादे' । चचन्द । 'त्रदि ६९ चेष्टायाम्' । तत्र-
न्द । 'कदि ७० क्रदि ७१ क्लदि ७२ आह्वाने रोदने च । चकन्द । चक्रन्द । चक्लन्द । 'क्लिदि
७३ परिदेवने' । चिक्लिन्द । 'शुन्ध ७४ शुद्धौ' । शुशुन्ध । नलोपः । शुध्यात् ।

अथ कवर्गीयान्ता अनुदात्तेतो द्विचत्वारिंशत् । 'शीकृ ७५ सेचने' । तालव्यादिः । 'दन्त्यादिः'
इत्येके । शीकते । शिशीके । 'लोकृ ७६ दर्शने' । लोकते । लुलोके । 'श्लोकृ ७७ संघाते'
संघातो ग्रन्थः । स चेह ग्रथ्यमानस्य व्यापारो ग्रन्थितुर्वा । आद्येऽकर्मको द्वितीये सकर्मकः ।
श्लोकते । 'द्रेकृ ७८ ध्रेकृ ७९ शब्दोत्साहयोः' । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके । दिध्रेके ।
'रेकृ ८० शङ्कायाम्' । रेकते । 'सेकृ ८१ स्रेकृ ८२ स्रकि ८३ श्रकि ८४ श्लकि ८५ गतौ'
त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः । सिसेके । 'शकि ८६ शङ्कायाम्'
शङ्कते । शशङ्के । 'अकि ८७ लक्षणे' । अङ्कते । आनङ्के । 'वकि ८८ कौटिल्ये' । वङ्कते ।
'मकि ८९ मण्डने' । मङ्कते । 'कक ९० लौल्ये' । लौल्यं गर्वश्चापल्यं च । ककते । चकके ।
'कुक ९१ वृक ९२ आदाने' । कोकते । चुकुके । वर्कते । ववृके । 'ऋदुपधेभ्यो लिटः कित्-
त्वं गुणात्पूर्वविप्रतिषेधेन' (वा ५९३) । 'चक ९३ तृप्तौ प्रतिघाते च' । चकते । चेके । 'ककि ९४
वकि ९५ श्वकि ९६ त्रकि ९७ ढौकृ ९८ त्रौकृ ९९ ष्वष्क १०० वस्क १०१ मस्क १०२ टिकृ
१०३ टीकृ १०४ तिकृ १०५ तीकृ १०६ रघि १०७ लघि १०८ गत्यर्थाः' । कङ्कते । चकङ्-
के । तुत्रौके । 'सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः' (वा ३४९९) । ष्व-
ष्कते । षष्वष्के । अत्र 'तृतीयो दन्त्यादिः' इत्येके । 'लघि' भोजननिवृत्तावपि । 'अघि १०९
वघि ११० मघि १११ गत्याक्षेपे' । आक्षेपो निन्दा । 'गतौ गत्यारम्भे च' इत्यन्ये । अङ्घते ।
आनङ्घे । वङ्घते । मङ्घते । 'मघि' कैतवे च । 'राघृ ११२ लाघृ ११३ द्राघृ ११४ सामर्थ्ये'

राघते । लाघते । 'श्राघृ' इत्यपि केचित् । 'द्राघृ' आयामे च । आयामो दैर्घ्यम् । द्राघते 'श्लाघृ ११९ कत्थने' । श्लाघते ।

अथ परस्मैपदिनः पञ्चाशत् । 'फक्क ११६ नीचैर्गतौ' । नीचैर्गतिर्मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क । 'तक ११७ हसने' । तकति । 'तकि ११८ कृच्छ्रजीवने' । तङ्कति । 'बुक्क ११९ भषणे' । भषणं श्वरवः । बुक्कति । 'कख १२० हसने' । प्रनिकखति । 'ओखृ १२१ राखृ १२२ लाखृ १२३ द्राखृ १२४ ध्राखृ १२५ शोषणालमर्थयोः' । ओखति । ओखांचकार । 'शाखृ १२६ श्लाखृ १२७ व्याप्तौ' । शाखति । 'उख १२८ उखि १२९ वख १३० वखि १३१ मख १३२ मखि १३३ णख १३४ णखि १३५ रख १३६ रखि १३७ लख १३८ लखि १३९ इख १४० इखि १४१ ईख १४२ वल्ग १४३ रगि १४४ लगि १४५ अगि १४६ वगि १४७ मगि १४८ तगि १४९ त्वगि १५० श्रगि १५१ श्लगि १५२ इगि १५३ रिगि १५४ लिगि १५५ गत्यर्थाः' । कवर्गद्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु 'रिख' 'त्रख' 'त्रिखि' 'शिखि' इत्यपि चतुरः केचित्पठन्ति ।

२२९० । अभ्यासस्यासवर्णे । ६ । ४ । ७८ । अभ्यासस्येवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । उवोख । संनिपातपरिभाषया 'इजादेः–' (सू २२३७) इत्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो न भवति सकृत्प्रवृत्तत्वात् । आङ्त्वाद्विपर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे कृते ततो दीर्घः । 'वार्णादाङ्गं बलीयः' (प ५६) इति न्यायात्परत्वाच्च । उङ्खति । ववखतुः । वङ्खति । मेखतुः । 'त्वगि' कम्पने च । 'युगि १५६ जुगि १५७ वुगि १५८ वर्जने' । युङ्गति । 'घघ १५९ हसने' । घघति । जघाघ । 'मघि १६० मण्डने' । मङ्घति । 'शिघि १६१ आघ्राणे' । शिङ्घति ।

अथ चवर्गीयान्ताः । तत्रानुदात्तेत एकविंशतिः । 'वर्च १६२ दीप्तौ' । वर्चते । 'षच १६३ सेचने सेवने च' । सचते । सेचे । सचिता । 'लोचृ १६४ दर्शने' लोचते । लुलोचे । 'शच १६५ व्यक्तायां वाचि' । शेचे । 'श्वच १६६ श्वचि १६७ गतौ' । श्वचते । श्वञ्चते । 'कच १६८ बन्धने' । कचते । 'कचि १६९ काचि १७० दीप्तिबन्धनयोः' । चकञ्चे । चकाञ्चे । 'मच १७१ मुचि १७२ कल्कने' । कल्कनं दम्भः शाठ्यं च । 'कथनम्' इत्यन्ये । मेचे । मुमुञ्चे । 'मचि १७३ धारणोच्छ्रायपूजनेषु' । ममञ्चे । 'पचि १७४ व्यक्तीकरणे' । पञ्चते । 'ष्टुच १७५ प्रसादे' । स्तोचते । तुष्टुचे । 'ऋज १७६ गतिस्थानार्जनोपार्जनेषु' । अर्जते । नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे । 'ऋजि १७७ भृजी १७८ भर्जने' । ऋञ्जते । 'उपसर्गादृति–' (सू ७४) इति वृद्धिः । प्रार्ञ्जते । ऋञ्जांचक्रे । आर्ञ्जिष्ट । भर्जते । बभृजे । अभर्जिष्ट । 'एजृ १७९ भ्रेजृ १८० भ्राजृ १८१ दीप्तौ' । एजांचक्रे । 'ईज १८२ गतिकुत्सनयोः' । ईजांचक्रे ।

अथ द्विसप्ततिर्व्रज्यन्ताः परस्मैपदिनः । 'शुच १८३ शोके' । शोचति । 'कुच १८४ शब्दे तारे' । कोचति । 'कुञ्च १८५ क्रुञ्च १८६ कौटिल्याल्पीभावयोः' । 'अनिदिताम्–' (सू ४१५) इति नलोपः । कुच्यात् । क्रुच्यात् । 'लुञ्च १८७ अपनयने । लुच्यात् । 'अञ्चु १८८ गतिपूजनयोः' । अच्यात् । गतौ तु नलोपः । पूजायां तु । अञ्च्यात् । 'वञ्चु १८९ चञ्चु

१. स्पष्टं चेदम् 'एओङ्'सूत्रभाष्ये ।

१९० तञ्चु १९१ त्वञ्चु १९२ मुञ्चु १९३ म्लुञ्चु १९४ मुचु १९५ म्लुचु १९६ गत्यर्थाः। वच्यात्। चच्यात्। तच्यात्। त्वच्यात्। अमुञ्चीत्। अम्लुञ्चीत्।

२२९१। जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।३।१।५८। एभ्यश्च्लेरङ् वा स्यात्। अम्रुचत्–अम्रोचीत्। अम्लुचत्–अम्लोचीत्। 'ग्रुचु १९७ ग्लुचु १९८ १९९ कुजु २०० स्तेयकरणे'। जुग्रोच। अग्रुचत्–अग्रोचीत्। जुग्लोच। अग्लुचत्–अग्लोचीत्। अकोजीत्। अखोजीत्। 'ग्लुञ्चु २०१ षस्ज २०२ गतौ'। अङ्। अग्लुचत्–अग्लुञ्चीत्। सस्य श्चुत्वेन शः, जश्त्वेन जः। सज्जति। अयमात्मनेपद्यपि। सज्जते। 'गुजि २०३ अव्यक्ते शब्दे'। गुञ्जति। गुञ्ज्यात्। 'अर्च २०४ पूजायाम्'। आनर्च। 'म्लेछ २०५ अव्यक्ते शब्दे'। अस्फुटेऽपशब्दे चेत्यर्थः। म्लेच्छति। मिम्लेच्छ। 'लछ २०६ लाछि २०७ लक्षणे'। ललच्छ। ललाञ्छ। 'वाछि २०८ इच्छायाम्'। वाञ्छति। 'आछि २०९ आयामे'। आञ्छति। 'अत आदेः' (सू २२४८) इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थम्। तेन दीर्घाभावान्न नुट्। आञ्छ। तपरकरणं मुखसुखार्थमिति मते तु आनाञ्छ। 'ह्रीछ २१० लज्जायाम्'। जिह्रीच्छ। 'हुर्छा २११ कौटिल्ये'। 'कौटिल्यमपसरणम्' इति मैत्रेयः। 'उपधायां च' (सू २२६५) इति दीर्घः। हूर्छति। 'मुर्छा २१२ मोहसमुच्छ्राययोः'। मूर्छति। 'स्फुर्छा २१३ विस्तृतौ'। स्फूर्छति। 'युच्छ २१४ प्रमादे'। युच्छति। 'उछि २१५ उञ्छे'। 'उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्' इति यादवः। उञ्छति। उञ्छांचकार। 'उछी २१६ विवासे'। विवासः समाप्तिः। प्रायेणायं विपूर्वः। व्युच्छति। 'ध्रज २१७ ध्रजि २१८ धृज २१९ धृजि २२० ध्वज २२१ ध्वजि २२२ गतौ'। ध्रजति। ध्रञ्जति। धर्जति। धृञ्जति। ध्वजति। ध्वञ्जति। 'कूज २२३ अव्यक्ते शब्दे'। चुकूज। 'अर्ज २२४ षर्ज २२५ अर्जने'। अर्जति। आनर्ज। सर्जति। ससर्ज। 'गर्ज २२६ शब्दे'। गर्जति। 'तर्ज २२७ भर्त्सने'। तर्जति। ततर्ज। 'कर्ज २२८ व्यथने'। चकर्ज। 'खर्ज २२९ पूजने च'। चखर्ज। 'अज २३० गतिक्षेपणयोः'। अजति।

२२९२। अजेर्व्यघञपोः ।२।४।५६। अजेर्वी इत्ययमादेशः स्यादार्धधातुके घञमपं च वर्जयित्वा। 'वलादावार्धधातुके वेष्यते' (वा १५९७)। विवाय। विव्यतुः। अत्र वकारस्य हल्परत्वात् 'उपधायां च' (सू २२६५) इति दीर्घे प्राप्ते 'अचः परस्मिन्' (सू ५०) इति स्थानिवद्भावेनाच्परत्वम्। न च 'न पदान्त–' (सू ५१) इति निषेधः। 'स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत्' (वा ४३१) इत्युक्तेः। थलि 'एकाचः' (सू २२४६) इतीण्निषेधे प्राप्ते।

२२९३। कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ।७।२।१३। एभ्यो लिट इड् न स्यात्। क्रादीनां चतुर्णां ग्रहणं नियमार्थम्। प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स ...

---

१. कुञ्जन्त्यत्र 'कुजि अव्यक्ते शब्दे' इति 'कुञ्ज'शब्दव्याख्याने मुकुटः। 'कुजि धातोर्धातुपाठेऽदर्शनात्' इति भानुजीदीक्षितस्तु तदुपलब्धधातुपाठपुस्तके तदद... लकः द्वासप्ततिसंख्यापूरणायातिक्लेशं वहतु। 'लतादिपिहितोदरे' इति मूलस्वा... 'कुजिरावरणार्थो लोकात्' इति वदन्क्षीरस्वाम्यपि कुजिधातुसत्त्वं मन्यत एव।

चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ।

२२९४ । अचस्तास्वत्थल्यनिटो नित्यम् । ७ । २ । ६१ । उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इड् न स्यात् ।

२२९५ । उपदेशेऽत्वतः । ७ । २ । ६२ । उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इड् न स्यात् ।

२२९६ । ऋतो भारद्वाजस्य । ७ । २ । ६३ । तासौ नित्यानिट ऋदन्तस्यैव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः—

'अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् ।
ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत् ॥'

न च स्तुद्र्वादीनामपि थलि विकल्पः शङ्क्यः । 'अचस्तास्वत्–' (सू २२९४) इति 'उपदेशेऽत्वतः' (सू २२९५) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः 'अनन्तरस्य–' (प ६२) इति न्यायात् । विवयिथ–विवेथ–आजिथ । विव्यथुः । विव्य । विवाय–विवय । विव्यिव । विव्यिम । वेता–अजिता । वेष्यति–अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ।

२२९७ । सिचि वृद्धिः परस्मैपदेषु । ७ । २ । १ । इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदे परे सिचि । अवैषीत्–आजीत् । अवेष्यत्–आजिष्यत् । 'तेज २३१ पालने' । तेजति । 'खज २३२ मन्थे' । खजति । 'खजि २३३ गतिवैकल्ये' । खञ्जति । 'एजृ २३४ कम्पने' । एजांचकार । 'टुओस्फूर्जा २३५ वज्रनिर्घोषे' । स्फूर्जति । पुस्फूर्ज । 'क्षि २३६ क्षये' । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः चिक्षयिथ–चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ।

२२९८ । अकृत्सार्वधातुकयोर्दीर्घः । ७ । ४ । २५ । अजन्तस्याङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् । 'क्षीज २३७ अव्यक्ते शब्दे' । कूजिना सहायं पठितुं युक्तः । चिक्षीज । 'लज २३८ लाजि २३९ भर्जने' । 'लाज २४० लाजि २४१ भर्त्सने च' । 'जज २४२ जजि २४३ युद्धे' । 'तुज २४४ हिंसायाम्' । तोजति । तुतोज । 'तुजि २४५ पालने' । 'गज २४६ गजि २४७ गृज २४८ गृजि २४९ मुज २५० मुजि २५१ शब्दार्थाः' । 'गज' मदने च । 'वज २५२ व्रज २५३ गतौ' । 'वदव्रज–' (सू २२६७) इति वृद्धिः । अव्राजीत् ।

अथ टवर्गीयान्ताः शाडन्ता अनुदात्तेतः षट्त्रिंशत् । 'अट्ट २५४ अतिक्रमहिंसयोः' । दोपधोऽयम् । 'तोपधः' इत्येके । अट्टते । आनट्टे । 'वेष्ट २५५ वेष्टने' । विवेष्टे । 'चेष्ट २५६ चेष्टायाम्' । अचेष्टिष्ट । 'गोष्ट २५७ लोष्ट २५८ संघाते' । जुगोष्टे । लुलोष्टे । 'घट्ट २५९ चलने' । जघट्टे । 'स्फुट २६० विकसने' । स्फोटते । पुस्फुटे । 'अठि २६१ गतौ' । अण्ठते । आनण्ठे । 'वठि २६२ एकचर्यायाम्' । ववण्ठे । 'मठि २६३ कठि २६४ शोके' । शोक इह आध्यानम् । मण्ठते । कण्ठते । 'मुठि २६५ पालने' । मुण्ठते । 'हेठ २६६ विबाधायाम्' । विबाधा शाठ्यम् । जिहेठे । 'एठ २६७ च' । एठांचक्रे । 'हिडि २६८ गत्य-

नादरयोः'। हिण्डते । जिहिण्डे । 'हुडि २६९ संघाते'। जुहुण्डे । 'कुडि २७० दा
चुकुण्डे । 'वडि २७१ विभाजने'। 'मडि २७२ च'। ववण्डे । 'भडि २७३ परिभाषणे'।
परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे । 'पिडि २७४ संघाते'। पिपिण्डे । 'मुडि
२७५ मार्जने'। मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते । 'तुडि २७६ तोडने'। तोडनं दारणं
हिंसनं च । तुण्डते । 'हुडि २७७ वरणे' । वरणं स्वीकारः । 'हरणे' इत्येके । हुण्डते ।
'चडि २७८ कोपे'। चण्डते । 'शडि २७९ रुजायां संघाते च'। शण्डते । 'तडि
ताडने'। तण्डते । 'पडि २८१ गतौ'। पण्डते । 'कडि २८२ मदे' । कण्डते । 'खडि
मन्थे'। 'हेडृ २८४ होडृ २८५ अनादरे'। जिहेडे । जुहोडे । 'बाडृ २८६ आप्लाव्ये'
बशादिः । आप्लाव्यमाप्लवः । बाडते । 'द्राडृ २८७ ध्राडृ २८८ विशरणे'। द्राडते । ध्राडते
'शाडृ २८९ श्लाघायाम्'। शाडते ।

अथ आ टवर्गीयान्तसमाप्तेः परस्मैपदिनः । 'शौटृ २९० गर्वे'। शौटति । शुशौट ।
'यौटृ २९१ बन्धे'। यौटति । 'म्लेटृ २९२ म्रेडृ २९३ उन्मादे'। द्वितीयो डान्तः ।
मध्ये पाठस्त्वर्थसाम्यात्प्राथतिवत् । म्लेटति । म्रेडति । 'कटे २९४ वर्षावरणयोः'।
इत्येके । चकाट । सिचि 'अतो हलादेर्लघोः' (सू २२८४) इति वृद्धौ प्राप्तायाम् ।

२२९९ । ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् । ७ । २ । ५ । हमयान्तस्य क्षणादे-
न्तस्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् । 'अट २९५ पट २९६ गतौ'।
आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः । 'रट २९७ परिभाषणे'। रराट । 'लट
२९८ बाल्ये'। ललाट । 'शट २९९ रुजाविशरणगत्यवसादनेषु'। शशाट । 'वट
वेष्टने'। ववाट । ववटतुः । ववटुः । ववटिथ । 'किट ३०१ खिट ३०२ त्रासे'। केटति ।
खेटति । 'शिट ३०३ षिट ३०४ अनादरे'। शेटति । शिशेट । सेटति । सिषेट । 'जट
झट ३०६ संघाते'। 'भट ३०७ भृतौ'। 'तट ३०८ उच्छ्राये'। 'खट ३०९ काङ्क्षायाम्'।
'णट ३१० नृत्तौ'। 'पिट ३११ शब्दसंघातयोः'। 'हट ३१२ दीप्तौ'। 'षट ३१३ अवयवे'।
'लुट ३१४ विलोडने'। 'डान्तोऽयम्' इत्येके। 'चिट ३१५ परप्रेष्ये'। 'विट ३१६ शब्दे'।
ट ३१७ आक्रोशे'। बशादिः। 'हिट' इत्येके । 'इट ३१८ किट ३१९ कटी ३२० गतौ'।
ति । केटति । कटति । ईकारः 'श्वीदितो निष्ठायाम्' (सू ३०३९) इतीण्निषेधार्थः । केचित्तु
मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ते च 'इ' 'ई' इति प्रश्लिष्य । अयति ।
ईयतुः । ईयुः । इययिथ-इयेथ । इयाय-इयय । दीर्घस्य तु 'इजादेश्च-' (सू २२३०)
मि अयांचकारेत्यादि उदाहरन्ति । 'मडि ३२१ भूषायाम्'। 'कुडि ३२२ वैकल्ये'।
ति । कुण्डत इति तु दाहे गतम् । 'मुड ३२३ प्रुड ३२४ मर्दने'। 'चुडि ३२५ अल्पीभा
वे'। 'मुडि ३२६ खण्डने'। मुण्डति । 'पुडि च' इत्येके । पुण्डति । 'रुटि ३२७ लुटि
स्तेये'। रुण्टति । लुण्टति । 'रुठि लुठि' इत्येके । 'रुडि लुडि' इत्यपरे । 'स्फुटिर्
विशरणे'। इरित्त्वादङ्वा । अस्फुटत्-अस्फोटीत् । 'स्फुटि' इत्यपि केचित् । इदित्त्वात्
स्फुण्टति । 'पठ ३३० व्यक्तायां वाचि'। पेठतुः । पेठिथ । अपठीत्-अपाठीत् । 'वठ
स्थौल्ये' । ववठतुः । ववठिथ । 'मठ ३३२ मदनिवासयोः'। 'कठ ३३३ कृच्छ्रजीवने'।
'रट ३३४ परिभाषणे'। 'रठ' इत्येके । 'हठ ३३५ प्लुतिशठत्वयोः'। 'बलात्कारे'।

के। हठति। जहाठ। रुठ ३३६ लुठ ३३७ उठ ३३८ उपघाते'। ओठति। 'ऊठ' इत्येके। ऊठाति। ऊठांचकार। 'पिठ ३३९ हिंसासंक्लेशनयोः'। 'शठ ३४० कैतवे च'। 'शुठ ३४१ प्रतिघाते'। शोठति। 'शुठि' इति स्वामी। शुण्ठन्ति। 'कुठि ३४२ च'। कुण्ठति। 'लुठी ३४३ आलस्ये प्रतिघाते च'। 'शुठि ३४४ शोषणे'। 'रुठि ३४५ लुठि ३४६ गतौ'। 'चुड्ड ३४७ भावकरणे'। भावकरणमभिप्रायसूचनम्। चुड्डति। चुचुड्ड। 'अड्ड ३४८ अभियोगे'। अड्डति। आनड्ड। 'कड्ड ३४९ कार्कश्ये'। कड्डति। चुड्डादयस्त्रयो दोपधाः। तेन क्विपि। चुत्। अत्। कत् इत्यादि। 'क्रीडृ ३५० विहारे'। चिक्रीड। 'तुडृ ३५१ तोडने'। तोडति। तुतोड। 'तूडृ' इत्येके। 'हुडृ ३५२ हूडृ ३५३ होडृ ३५४ गतौ'। हुडयात्–हूडयात्–होडयात्। 'रौडृ ३५५ अनादरे'। 'रोडृ ३५६ लोडृ ३५७ उन्मादे'। 'अड ३५८ उद्यमे'। अडति। आड। आडतुः। आडुः। 'लड ३५९ विलासे'। लडति। डलयोरैक्यस्मरणाल्ललतीति स्वाम्यादयः। 'कड ३६० मदे'। कडति। 'कडि' इत्येके। कण्डति। 'गडि ३६१ वदनैकदेशे'। गण्डति। इति टवर्गीयान्ताः।

अथ पवर्गीयान्ताः। तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत्। 'तिपृ ३६२ तेपृ ३६३ ष्टिपृ ३६४ ष्टेपृ ३६५ क्षरणार्थाः'। आद्योऽनुदात्तः। क्षीरस्वामी त्वयं सेडिति बभ्राम। तेपते। तितिपे। क्रादिनियमादिट्। तितिपिषे। तेप्ता। तेप्स्यते।

२३०० । लिङ्सिचावात्मनेपदेषु । १ । २ । ११ । इक्समीपाद्धलः परौ झलादी लिङात्मनेपदपरः सिचेत्येतौ कितौ स्तः। कित्त्वान्न गुणः। तिप्सीष्ट। तिप्सीयास्ताम्। तिप्सीरन्। लुङि 'झलो झलि' (सू २२८१) इति सलोपः। अतिप्त। अतिप्साताम्। अतिप्सत। तेपते। तितिपे। तिष्टिपे। तिष्टिपाते। तिष्टिपिरे। तिष्टेपे। तिष्टेपाते। तिष्टेपिरे। 'तेपृ' कम्पने च। 'ग्लेपृ ३६६ दैन्ये'। ग्लेपते। 'टुवेपृ ३६७ कम्पने'। वेपते। 'केपृ ३६८ गेपृ ३६९ ग्लेपृ ३७० च'। चात्कम्पने गतौ च। सूत्रविभागादिति स्वामी। मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पन इत्यपेक्षत इत्याह। ग्लेपेरर्थभेदात्पुनः पाठः। 'मेपृ ३७१ रेपृ ३७२ लेपृ ३७३ गतौ'। 'त्रपूष् ३७४ लज्जायाम्'। त्रपते।

२३०१ । तृफलभजत्रपश्च । ६ । ४ । १२२ । एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च। त्रेपे। त्रेपाते। त्रेपिरे। ऊदित्त्वादिड्वा। त्रपिता–त्रप्ता। त्रपिषीष्ट–त्रप्सीष्ट। 'कपि ३७५ चलने'। कम्पते। चकम्पे। 'रबि ३७६ लबि ३७७ अबि ३७८ शब्दे'। ररम्बे। ललम्बे। आनम्बे। 'लबि ३७९ अवस्रंसने च'। 'कबृ ३८० वर्णे'। चकबे। 'क्लीबृ ३८१ अधाष्टर्ये'। चिक्लीबे। 'क्षीबृ ३८२ मदे'। क्षीबते। 'शीभृ ३८३ कत्थने'। शीभते। 'चीभृ ३८४ च'। 'रेभृ ३८५ शब्दे'। रिरेभे। 'अभिरभी' क्वचित्पठ्येते। अम्भते। रम्भते। 'ष्टभि ३८६ स्कभि ३८७ प्रतिबन्धे'। स्तम्भते। उत्तम्भते। 'उदः स्थास्तम्भोः–' (सू ११८) इति पूर्वसवर्णः। विस्तम्भते। 'स्तन्भेः' (सू २२७२) इति षत्वं तु न भवति। श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात्। तद्बीजं तु '–स्थास्तम्भोः–' (सू ११८) इति पवर्गीयोपधपाठः 'स्तन्भेः' (सू २२७२) इति तवर्गीयोपधपाठश्चेति माधवः। केचिदस्य टकार औपदेशिक इत्याहुः। तन्मते टम्भते। टष्टम्भे। 'जभि ३८८ जृभि ३८९ गात्रविनामे'।

२३०२। रधिजभोरचि।७।१।६१। एतयोर्नुमागमः स्यादचि। जम्भते। जजम्भे। जम्भिता। अजम्भिष्ट। जृम्भते। जजृम्भे। 'शल्भ ३९० कत्थने'। शशल्भे। 'वल्भ ३९१ भोजने'। दन्त्योष्ठ्यादिः। ववल्भे। 'गल्भ ३९२ धार्ष्ट्ये'। गल्भते। 'श्रम्भु ३९३ प्रमादे'। तालव्यादिर्दन्त्यादिश्च। श्रम्भते। स्रम्भते वा। 'ष्टुभु ३९४ स्तम्भे'। स्तोभते। विष्टोभते। तुष्टुभे। व्यष्टोभिष्ट।

अथ परस्मैपदिनः। 'गुपू ३९५ रक्षणे'।

२३०३। गुपूधूपविच्छिपणिपनिभ्य आयः।३।१।२८। एभ्य आयप्रत्ययः स्यात्स्वार्थे। 'पुगन्त–' (सू २१८९) इति गुणः।

२३०४। सनाद्यन्ता धातवः।३।१।३२। सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः। धातुत्वाल्लडादयः। गोपायति।

२३०५। आयादय आर्धधातुके वा।३।१।३१। आर्धधातुकविवक्षायामायादयो वा स्युः।

२३०६। कास्प्रत्ययादाममन्त्रे लिटि।३।१।३५। कास्धातोः प्रत्ययान्तेभ्यश्चाम्स्याल्लिटि, न तु मन्त्रे। 'कास्यनेकाज्ग्रहणं कर्तव्यम्' (वा १७९६)। सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाच्यमित्यर्थः।

२३०७। आर्धधातुके।६।४।४६। इत्यधिकृत्य।

२३०८। अतो लोपः।६।४।४८। आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे। गोपायां चकार। गोपायां बभूव। गोपायामास। जुगोप। जुगुपतुः। ऊदित्वाद्वेट्। जुगोपिथ–जुगोप्थ। गोपायिता–गोपिता–गोप्ता। गोपाय्यात्–गुप्यात्। अगोपायीत्–अगोपीत्–अगौप्सीत्। 'धूप ३९६ संतापे'। धूपायति। धूपायां चकार। दुधूप। धूपायितासि। धूपितासि। 'जप ३९७ जल्प ३९८ व्यक्तायां वाचि'। 'जप' मानसे च। 'चप ३९९ सान्त्वने'। 'षप ४०० समवाये'। समवायः संबन्धः सम्यगवबोधो वा। सपति। 'रप ४०१ लप ४०२ व्यक्तायां वाचि'। 'चुप ४०३ मन्दायां गतौ'। चोपति। चचोप। चोपिता। 'तुप ४०४ तुम्प ४०५ त्रुप ४०६ त्रुम्प ४०७ तुफ ४०८ तुम्फ ४०९ त्रुफ ४१० त्रुम्फ ४११ हिंसार्थाः'। तोपति। तुतोप। तुम्पति। तुतुम्प। तुतुम्पतुः। संयोगात्परस्य लिटः कित्त्वाभावान्नलोपो न। 'किदाशिषि' (सू२२१६) इति कित्त्वान्नलोपः। तुप्यात्। 'प्रात्तुम्पतौ गवि कर्तरि' (ग सू १५८) इति पारस्करादिगणे पाठात्सुट्। प्रस्तुम्पति गौः। शि...पानिर्देशाद्यङ्लुकि न। प्रतोतुम्पीति। त्रोपति। त्रुम्पति। तोफति। तुम्फति। त्रोफति। त्रुम्फति। इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः। अन्ये सरेफाः। आद्याश्चत्वारः प्रथमान्ताः ततो द्वितीयान्ताः। अष्टावप्युकारवन्तः। 'पर्प ४१२ रफ ४१३ रफि ४१४ अर्ब ४१५ पर्ब ४१६ लर्ब ४१७ बर्ब ४१८ मर्ब ४१९ कर्ब ४२० खर्ब ४२१ गर्ब ४२२ शर्ब ४२३ षर्ब ४२४ चर्ब ४२५ गतौ'। आद्यः प्रथमान्तः। ततो द्वौ द्वितीयान्तौ। तत एकादश तृतीयान्ताः। द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः। पर्पति। पपर्प। रफति। रम्फति। अर्बति। आनर्ब। पर्बति। लर्बति। बर्बति। पवर्गीयादिरयम्। मर्बति। कर्बति। खर्बति। गर्बति। शर्बति। सर्बति। चर्बति। 'कुबि ४२६ आच्छादने'। कुम्बति।

४२७ तुबि ४२८ अर्दने' । तुम्बति । तुम्बति । 'चुबि ४२९ वक्त्रसंयोगे' । चुम्बति । 'षृभु ४३० षृम्भु ४३१ हिंसार्थौ' । सर्भति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । 'षिभु षिम्भु' इत्येके । सेभति । सिम्भति । 'शुभ ४३२ शुम्भ ४३३ भाषणे' । 'भासने' इत्येके । 'हिंसायाम्' इत्यन्ये ।

अथानुनासिकान्ताः । तत्र क्रम्यन्ता अनुदात्तेतो दश । 'घिणि ४३४ घुणि ४३५ घृणि ४३६ ग्रहणे' । नुम् । ष्टुत्वम् । घिण्णते । जिघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे । 'घुण ४३७ घूर्ण ४३८ भ्रमणे' । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ । 'पण ४३९ व्यवहारे स्तुतौ च' । 'पन ४४० च' । स्तुतावित्येव संबध्यते पृथङ्निर्देशात् । पनिसाहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायां चकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पणिषीष्ट । पनायति । पनायां चकार । पेने । 'भाम ४४१ क्रोधे' । भामते । बभामे । 'क्षमूष् ४४२ सहने' । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षन्ध्वे । चक्षमिवहे ।

२३०९ । म्वोश्च । ८ । २ । ६५ । मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे । णत्वम् । चक्षमिवहे–चक्षण्वहे । चक्षमिमहे–चक्षण्महे । क्षमिष्यते–क्षंस्यते । क्षमेत । आशिषि । क्षमिषीष्ट–क्षंसीष्ट । अक्षमिष्ट–अक्षंस्त । 'कमु ४४३ कान्तौ' । कान्तिरिच्छा ।

२३१० । कमेर्णिङ् । ३ । १ । ३० । स्वार्थे । ङित्त्वात्तङ् । कामयते ।

२३११ । अयामन्ताल्वाय्येत्न्विष्णुषु । ६ । ४ । ५५ । 'आम्' 'अन्त' 'आलु' 'आय्य' 'इत्नु' 'इष्णु' एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयां चक्रे । 'आयादय आर्धधातुके वा' (सू २३०५) । चकमे । कामयिता–कमिता । कामयिष्यते–कमिष्यते ।

२३१२ । णिश्रिद्रुस्रुभ्यः कर्तरि चङ् । ३ । १ । ४८ । ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात्कर्त्रर्थे लुङि परे । 'अकाम्' 'इ' 'अत' इति स्थिते ।

२३१३ । णेरनिटि । ६ । ४ । ५१ । अनिडादावार्धधातुके परे णेर्लोपः स्यात् । परत्वात् 'एरनेकाचः–' (सू २७२) इति यणि प्राप्ते । 'ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन' (वा ४०८०) इति वार्तिकम् । णिलोपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्तु 'अनिटि' इति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । आटिटत् । गुणः । कारणाः । वृद्धिः । कारकः । दीर्घः । कार्यते ।

२३१४ । णौ चङ्युपधाया ह्रस्वः । ७ । ४ । १ । चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ।

२३१५ । चङि । ६ । १ । ११ । चङि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ।

२३१६ । सन्वल्लघुनि चङ्परेऽनग्लोपे । ७ । ४ । ९३ । 'चङ्परे' इति बहुव्रीहिः ।

स च 'अङ्गस्य' इति च द्वयमप्यावर्तते। अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तस्य यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति। अथवा 'अङ्गस्य' इति नावर्तते। चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत्।

२३१७। सन्यतः। ७। ४। ७९। अभ्यासस्यात इकारः स्यात्सनि।

२३१८। दीर्घो लघोः। ७। ४। ९४। लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये। अचीकमत। णिङभावपक्षे। 'कमेश्च्लेश्चङ्वक्तव्यः' (वा १८३९)। णेरभावान्न दीर्घसन्वद्भावौ। अचकमत।

संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते।
तत्रैव दीर्घः सन्वच्च नानेकाश्विति माधवः॥
चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते।
किं त्वस्यावयवः कश्चित्तस्मादेकाश्विदं द्वयम्॥
वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात्।
ङणौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे॥
चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया।
णेर्विशेष्यं संनिहितं लघुनीत्यङ्गमेव वा॥
इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात्।
णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये॥

अथ क्रम्यन्तास्त्रिंशत्परस्मैपदिनः। 'अण ४४४ रण ४४५ वण ४४६ भण ४४७ मण ४४८ कण ४४९ क्वण ४५० व्रण ४५१ भ्रण ४५२ ध्वण ४५३ शब्दार्थाः'। अणति। रणति। वणति। वकारादित्वादेत्वाभ्यासलोपौ न। ववणतुः। ववणिथ। 'धणिः' अपि केश्चित्पठ्यते। धणति। 'ओणृ ४५४ अपनयने'। ओणति। ओणांचकार। 'शोणृ ४५५ वर्णगत्योः'। शोणति। शुशोण। 'श्रोणृ ४५६ संघाते'। श्रोणति। 'श्लोणृ ४५७ च'। शोणादयस्त्रयः तालव्योष्मादयः। 'पैणृ ४५८ गतिप्रेरणश्लेषणेषु'। 'प्रैणृ' इति क्वचित्पठ्यते। पिपैण। 'ध्रण ४५९ शब्दे'। उपदेशे नान्तोऽयम्। 'रषाभ्याम्–' (सू २३५) इति णत्वम्। ध्रणति। नोपदेशफलं यङ्लुकि। दंध्रन्ति। 'बण' इत्यपि केचित्। बेणतुः। बेणिथ। 'कनी ४६० दीप्तिकान्तिगतिषु'। चकान। 'ष्टन ४६१ वन ४६२ शब्दे'। स्तनति। वनति। 'वन ४६३ षण ४६४ संभक्तौ'। वनेरर्थभेदात्पुनः पाठः। सनति। ससान। सेनतुः।

२३१९। ये विभाषा। ६। ४। ४३। जनसनखनामात्त्वं वा स्याद्यादौ क्ङिति। सायात्, सन्यात्। 'अम ४६५ गत्यादिषु'। 'कनीदीप्तिकान्तिगति–' इत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन ग्रहः। अमति। आम। 'द्रम ४६६ हम्म ४६७ मीमृ ४६८ गतौ'। द्रमति। दद्राम। 'ह्म्यन्त–' (सू २२९९) इति न वृद्धिः। अद्रमीत्। हम्मति। जहम्म। मीमति। मिमीम। अयं शब्दे च। 'चमु ४६९ छमु ४७० जमु ४७१ झमु ४७२ अदने'।

२३२०। ष्ठिवुक्लमुचमां शिति। ७। ३। ७५। एषामचो दीर्घः स्याच्छिति। 'आङि चम इति वक्तव्यम्' (वा ४५६२)। आचामति। 'आङि' किम्। चमति। विचमति। अचमीत्। जिमिं केचित्पठन्ति। जेमति। 'क्रमु ४७३ पादविक्षेपे'।

२३२१। वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः। ३। १। ७०। एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे।

२३२२। क्रमः परस्मैपदेषु। ७। ३। ७६। क्रमेर्दीर्घः स्यात्परस्मैपदे परे शिति। क्राम्यति-क्रामति। चक्राम। क्राम्यतु-क्रामतु।

२३२३। स्नुक्रमोरनात्मनेपदनिमित्ते। ७। २। ३६। अत्रेवेट्। अक्रमीत्।

अथ रेवत्यन्ता अनुदात्तेतः। 'अय ४७४ वय ४७५ पय ४७६ मय ४७७ चय ४७८ तय ४७९ णय ४८० गतौ'। अयते।

२३२४। दयायासश्च। ३। १। ३७। 'दय' 'अय' 'आस्' एभ्य आम्स्याल्लिटि। अयांचक्रे। अयिता। अयिषीष्ट।

२३२५। विभाषेटः। ८। ३। ७९। इणः परो य इट् ततः परेषां षीध्वं लुङ्लिटां धस्य वा मूर्धन्यः स्यात्। अयिषीढ्वम्-अयिषीध्वम्। आयिष्ट। आयिढ्वम्-आयिध्वम्।

२३२६। उपसर्गस्यायतौ। ८। २। १९। अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्। प्लायते-पलायते। निस्दुसो रुत्वस्यासिद्धत्वान्न लत्वम्। निरयते। दुरयते। निर्दुरोस्तु निलयते। दुलयते। 'प्रत्ययः' इति त्विणो रूपम्। अथ कथम् 'उदयति विततोर्ध्वरश्मिरज्जौ' इति माघः। 'इट' 'किट' 'कटी' इत्यत्र प्रश्लिष्टस्य एर्भविष्यति। यद्वा 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' (प ९७)। चक्षिङो ङित्करणाज्ज्ञापकात्। वादित्वात् ववये। पेये। मेये। चेये। तेये। प्रणयते। नेये। 'दय ४८१ दानगतिरक्षणहिंसादानेषु'। आदानं ग्रहणम्। दयां चक्रे। 'रय ४८२ गतौ'। 'ऊयी ४८३ तन्तुसंताने'। ऊयां चक्रे। 'पूयी ४८४ विशरणे दुर्गन्धे च'। पूयते। पुपूये। 'क्नूयी ४८५ शब्दे उन्दे च'। चुक्नूये। 'क्ष्मायी ४८६ विधूनने'। चक्ष्माये। 'स्फायी ४८७ ओप्यायी ४८८ वृद्धौ'। स्फायते। पस्फाये। प्यायते।

२३२७। लिड्यङोश्च। ६। १। २९। लिटि यङि च प्यायः पीभावः स्यात्। पुनः प्रसङ्ग-विज्ञानात्पीशब्दस्य द्वित्वम्। 'एरनेकाचः-' (सू २७२) इति यण्। पिप्ये। पिप्याते। पिप्यिरे।

२३२८। दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्। ३। १। ६१। एभ्यश्च्ले-श्चिण्वा स्यादेकवचने तशब्दे परे।

२३२९। चिणो लुक्। ६। ४। १०४। चिणः परस्य तशब्दस्य लुक्स्यात्। अप्यायि-अप्यायिष्ट। 'तायृ ४८९ संतानपालनयोः'। संतानः प्रबन्धः। तायते। तताये। अतायि-अतायिष्ट। 'शल ४९० चलनसंवरणयोः'। 'वल ४९१ वल्ल ४९२ संवरणे संचरणे च'। ववले। ववल्ले। 'मल ४९३ मल्ल ४९४ धारणे'। मेले। ममल्ले। 'भल ४९५ भल्ल ४९६ परिभाषण-हिंसादानेषु'। बभेले। बभल्ले। 'कल ४९७ शब्दसंख्यानयोः'। कलते। चकले। 'कल्ल ४९८ अव्यक्ते शब्दे'। कल्लते। 'अशब्दे' इति स्वामी। अशब्दस्तूष्णींभाव इति च। 'तेवृ ४९९ देवृ ५०० देवने'। तितेवे। दिदेवे। 'षेवृ ५०१ गेवृ ५०२ ग्लेवृ ५०३ पेवृ ५०४ मेवृ ५०५ म्लेवृ ५०६ सेवने'। 'परिनिविभ्यः-' (सू २२७५) इति षत्वम्। परिषेवते। सिषेवे। अयं षोपदेशोऽपीति न्यासकारादयः। तद्भाष्यविरुद्धम्। गेवते। जिगेवे। जिग्लेवे। पिपेवे। मेवते। म्लेवते। 'शेवृ' 'खेवृ' 'क्लेवृ' इत्यप्येके। 'रेवृ ५०७ प्लवगतौ'। प्लवगतिः प्लुतगतिः। रेवते।

अथावत्यन्ताः परस्मैपदिनः। 'मव्य ५०८ बन्धने'। ममव्य। 'सूर्क्ष्य ५०९ ईर्क्ष्य ५१०

ईर्ष्य ५११ ईर्ष्यार्थाः'। 'हय ५१२ गतौ'। अहयीत्। यान्तत्वान्न वृद्धिः। 'शुच्य ५१३ अभिषवे। अवयवानां शिथिलीकरणं सुरायाः संधानं वाभिषवः स्नानं च। शुशुच्य। 'चुच्य' इत्येके। 'हर्य ५१४ गतिकान्त्योः'। जहर्य। 'अल ५१५ भूषणपर्याप्तिवारणेषु'। अलति। आल।

२३३०। अतो ल्रान्तस्य। ७। २। २। 'ल्र्' इति लुप्तषष्ठीकम्। अतः समीपौ यौ लरौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि। 'नेटि' (सू २२६८) इति निषेधस्य 'अतो हलादेः' (सू २२८४) इति विकल्पस्य चापवादः। मा भवानालीत्। अयं स्वरितेदित्येके। तन्मतेऽलते इत्याद्यपि। 'ञिफला ५१६ विशरणे'। 'तृफल-' (सू २३०१) इत्येत्त्वम्। फेलतुः। फेलुः। अफालीत्। 'मील ५१७ श्मील ५१८ स्मील ५१९ क्ष्मील ५२० निमेषणे'। निमेषः संकोचः। द्वितीयस्तालव्यादिः। तृतीयो दन्त्यादिः। 'पील ५२१ प्रतिष्टम्भे'। प्रतिष्टम्भो रोधनम्। 'णील ५२२ वर्णे'। निनील। 'शील ५२३ समाधौ'। शीलति। 'कील ५२४ बन्धने'। 'कूल ५२५ आवरणे'। 'शूल ५२६ रुजायां संघोषे च'। तूल ५२७ निष्कर्षे'। निष्कर्षो निष्कोषणम्। तच्चान्तर्गतस्य बहिर्निःसारणम। तुतूल। 'पूल ५२८ संघाते'। मूल ५२९ प्रतिष्ठायाम्। 'फल ५३० निष्पत्तौ'। फेलतुः। फेलुः। 'चुल्ल ५३१ भावकरणे'। भावकरणमभिप्रायाविष्कारः। 'फुल्ल ५३२ विकसने'। 'चिल्ल ५३३ शैथिल्ये भावकरणे च'। 'तिल ५३४ गतौ'। तेलति। 'तिल्ल' इत्येके। तिल्लति। 'वेल ५३५ चेल ५३६ केल ५३७ खेल ५३८ क्ष्वेल ५३९ वेल्ल ५४० चलने'। पञ्च ऋदितः षष्ठो लोपधः। 'पेल ५४१ फेल ५४२ शेल ५४३ गतौ'। 'षेल' इत्येके। 'स्खल ५४४ संचलने'। चस्खाल। अस्खालीत्। 'खल ५४५ सञ्चये'। 'गल ५४६ अदने'। गलति। अगालीत्। 'षल ५४७ गतौ'। सलति। 'दल ५४८ विशरणे'। 'श्वल ५४९ श्वल्ल ५५० आशुगमने'। शश्वाल। अश्वालीत्। अश्वल्लीत्। 'खोल ५५१ खोर्ऋ ५५२ गतिप्रतिघाते'। खोलति। खोरति। 'धोर्ऋ ५५३ गतिचातुर्ये'। धोरति। 'त्सर ५५४ छद्मगतौ'। तत्सार। अत्सारीत्। 'क्मर ५५५ हूर्च्छने'। चक्मार। 'अभ्र ५५६ वभ्र ५५७ मभ्र ५५८ चर ५५९ गत्यर्थाः'। चरतिर्भक्षणेऽपि। अभ्रति। आनभ्र। मा भवानभ्रीत्। अङ्गान्त्यरेफस्यातः समीपत्वाभावान्न वृद्धिः। 'ष्ठिवु ५६० निरसने'। 'ष्ठिवुक्लमु-' (सू २३२०) इति दीर्घः। ष्ठीवति। अस्य द्वितीयस्थकारठकारो वेति वृत्तिः। तिष्ठेव। तिष्ठिवतुः। तिष्ठिवुः। टिष्ठेव। टिष्ठिवतुः। टिष्ठिवुः। 'हलि च' (सू ३५४) इति दीर्घः। ष्ठीव्यात्। 'जि ५६१ जये'। अयमजन्तेषु पठितुं युक्तः। उत्कर्षप्राप्तिः। अकर्मकोऽयम्। जयति।

२३३१। सन्लिटोर्जेः। ७। ३। ५७। जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात्। जिगाय। जिग्यतुः। जिग्युः। जिगयिथ-जिगेथ। जिगाय-जिगय। जिग्यिव। जिग्यिम। जेता। जीयात्। अजैषीत्। 'जीव ५६२ प्राणधारणे'। जिजीव। 'पीव ५६३ मीव ५६४ तीव ५६५ णीव ५६६ स्थौल्ये'। पिपीव। मिमीव। तितीव। निनीव। 'क्षीवु ५६७ क्षेवु ५६८ निरसने'। 'उर्वी ५६९ तुर्वी ५७० थुर्वी ५७१ दुर्वी ५७२ धुर्वी ५७३ हिंसार्थाः'। ऊर्वा चकार। 'उपधायां च' (सू २२६५) इति दीर्घः। 'गुर्वी ५७४ उद्यमने'। गूर्वति। जुगूर्व। 'मुर्वी ५७५ बन्धने'। 'पुर्व ५७६ पर्व ५७७

५७८ पूरणे' । 'चर्व ५७९ अदने' । 'भर्व ५८० हिंसायाम्' । 'कर्व ५८१ खर्व ५८२ गर्व ५८३ दर्पे' । 'अर्व ५८४ शर्व ५८५ षर्व ५८६ हिंसायाम्' । आनर्व । शर्वति । सर्वति । 'इवि ५८७ व्याप्तौ' । इन्वति । इन्वां चकार । 'पिवि ५८८ मिवि ५८९ णिवि ५९० सेचने' । तृतीयो मूर्धन्योष्मादिरित्येके । 'सेवने' इति तरङ्गिण्याम् । पिन्वति । पिपिन्व । 'हिवि ५९१ दिवि ५९२ धिवि ५९३ जिवि ५९४ प्रीणनार्थाः' । हिन्वति । दिन्वति ।

२३३२ । धिन्विकृण्व्योर च । ३ । १ । ८० । अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । 'अतो लोपः' (सू. २३०८) । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वन्ति ।

२३३३ । लोपश्चास्यान्यतरस्यां म्वोः । ६ । ४ । १०७ । असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः–धिनुवः । धिन्मः–धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ।

२३३४ । उतश्च प्रत्ययादसंयोगपूर्वात् । ६ । ४ । १०६ । असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्य हेर्लुक्स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वतीत्यादि । 'रिवि ५९५ रवि ५९६ धवि ५९७ गत्यर्थाः' । रिण्वति । रण्वति । धन्वति । 'कृवि ५९८ हिंसाकरणयोश्च' । चकाराद्गतौ । 'कृणोति' इत्यादि धिनोतिवत् । अयं स्वादौ च । 'मव ५९९ बन्धने' । मवति । मेवतुः । मेवुः । अमवीत्–अमावीत् । 'अव ६०० रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु' । अवति । आव । मा भवानवीत् । 'धावु ६०१ गतिशुद्ध्योः' । स्वरितेत् । धावति–धावते । दधाव–दधावे ।

अथोष्मान्ता आत्मनेपादिनः । 'धुक्ष ६०२ धिक्ष ६०३ संदीपनक्लेशनजीवनेषु' । धुक्षते । दुधुक्षे । धिक्षते । दिधिक्षे । 'वृक्ष ६०४ वरणे' । वृक्षते । ववृक्षे । 'शिक्ष ६०५ विद्योपादाने' । शिक्षते । 'भिक्ष ६०६ भिक्षायामलाभे लाभे च' । भिक्षते । 'क्लेश ६०७ अव्यक्तायां वाचि' । 'बाधने' इति दुर्गः । क्लेशते । चिक्लेशे । 'दक्ष ६०८ वृद्धौ शीघ्रार्थे च' । दक्षते । ददक्षे । 'दीक्ष ६०९ मौण्ड्येज्योपनयननियमव्रतादेशेषु' । दीक्षते । दिदीक्षे । 'ईक्ष ६१० दर्शने' । ईक्षां चक्रे । 'ईष ६११ गतिहिंसादर्शनेषु' । ईषां चक्रे । 'भाष ६१२ व्यक्तायां वाचि' । भाषते । 'वर्ष ६१३ स्नेहने' । दन्त्योष्ठ्यादिः । ववर्षे । 'गेषृ ६१४ अन्विच्छायाम्' । 'ग्लेषृ' इत्येके । अन्विच्छा अन्वेषणम् । जिगेषे । 'पेषृ ६१५ प्रयत्ने' । पेषते । 'जेषृ ६१६ णेषृ ६१७ एषृ ६१८ प्रेषृ ६१९ गतौ' । जेषते । नेषते । एषां चक्रे । पिप्रेषे । 'रेषृ ६२० हेषृ ६२१ ह्रेषृ ६२२ अव्यक्ते शब्दे' । आद्यो वृकशब्दे । ततो द्वा अश्वशब्दे । रेषते । हेषते । ह्रेषते । 'कासृ ६२३ शब्दकुत्सायाम्' । कासां चक्रे । 'भासृ ६२४ दीप्तौ' । बभासे । 'नासृ ६२५ रासृ ६२६ शब्दे' । नासते । प्रणासते । 'णस ६२७ कौटिल्ये' । नसते । 'भ्यस ६२८ भये' । भ्यसते । बभ्यसे । 'आङः शसि ६२९ इच्छायाम्' । आशंसते । आशशंसे । 'ग्रसु ६३० ग्लसु ६३१ अदने' । जग्रसे । जग्लसे । 'ईह ६३२ चेष्टायाम्' । ईहां चक्रे । 'बहि ६३३ महि ६३४ वृद्धौ' । बंहते । बबंहे । मंहते । 'अहि ६३५ गतौ' । अंहते । आनंहे । 'गर्हे ६३६ गल्ह ६३७ कुत्सायाम्' । जगर्हे । जगल्हे । 'बर्ह ६३८ बल्ह ६३९ प्राधान्ये' ।

ओष्ठ्यादी । 'वर्ह ६४० वल्ह ६४१ परिभाषणहिंसाच्छादनेषु' । दन्त्योष्ठ्यादी केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः । 'प्लिह ६४२ गतौ' । पिप्लिहे 'वेह ६४३ जेह ६४४ बाह ६४५ प्रयत्ने' । आद्यो दन्त्योष्ठ्यादिः । अन्त्यः केवलोष्ठ्यादिः 'उभावप्योष्ठ्यादी' इत्येके । 'दन्त्योष्ठ्यादी' इत्यपरे । जेहतिर्गत्यर्थोऽपि । ववाहे । 'द्राह ६४६ निद्राक्षये' । 'निक्षेपे' इत्येके । 'काशृ ६४७ दीप्तौ' । चकाशे । 'ऊह ६४८ वितर्के' ऊहां चक्रे । 'गाहू ६४९ विलोडने' । गाहते । जगाहे । जगाहिषे । जघाक्षे । जगाहिढ्वे जगाहिध्वे-जगाढ्वे ।

२३३५ । ढो ढे लोपः । ८ । ३ । १३ । ढस्य लोपः स्याड्ढे परे । गाहिता-गाढा । गाहिष्यते-घाक्ष्यते । गाहिषीष्ट-घाक्षीष्ट । अगाहिष्ट-अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् । अघाक्षि । 'गृहू ६५० ग्रहणे' । गर्हते । जगृहे । 'ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन' (वा ५९३) । जगृहिषे-जघृक्षे । जघृढ्वे । गर्हिता-गर्ढा । गर्हिष्यते-घर्क्ष्यते । गर्हिषीष्ट-घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ।

२३३६ । शल इगुपधादनिटः क्सः । ३ । १ । ४५ । इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् । अघृक्षत ।

२३३७ । क्सस्याचि । ७ । ३ । ७२ । अजादौ तङि क्सस्य लोपः स्यात् । 'अलोऽन्त्यस्य' (सू ४२) अघृक्षाताम् । अघृक्षन्त । 'ग्लह ६५१ च' । ग्लहते । 'घुषि ६५२ कान्तिकरणे' । घुंषते । जुघुंषे । केचित् 'घष' इत्यदुपधं पठन्ति ।

अथार्हत्यन्ताः परस्मैपदिनः । 'घुषिर् ६५३ अविशब्दने' । विशब्दनं प्रतिज्ञानं तस्मादन्यस्मिन्नर्थे इत्येके । 'शब्दे' इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्वाद् अघुषत्-अघोषीत् । 'अक्षू ६५४ व्याप्तौ' ।

२३३८ । अक्षोऽन्यतरस्याम् । ३ । १ । ७५ । अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रर्थे सार्वधातुके परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्ति । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ-आनष्ठ । अक्षिता-अष्टा । अक्षिष्यति । 'स्कोः' (सू ३८०) कलोपः । 'षढोः कः सि' (सू २९५) । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्षतु । आक्ष्णोत् । आक्ष्णवत् । अक्ष्णुयात् । अक्ष्यात् । ऊदित्त्वाद्वेट् । 'नेटि' (सू २२६८) भवानक्षीत् । आक्षिष्टाम् । आक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः । 'तक्षू ६५५ त्वक्षू ६५६ तनूकरणे' ।

२३३९ । तनूकरणे तक्षः । ३ । १ । ७६ । श्नुः स्याद्वा शब्विषये । तक्ष्णोति-तक्षति वा काष्ठम् । ततक्षिथ-ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । 'तनूकरणे' किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः । 'उक्ष ६५७ सेचने' । उक्षां चकार । 'रक्ष ६५८ पालने' । 'णिक्ष ६५९ चुम्बने' । प्रणिक्षति । 'तृक्ष ६६० स्तृक्ष ६६१ णक्ष ६६२ गतौ' । तृक्षति । स्तृक्षति । नक्षति । 'वक्ष ६६३ रोषे' । 'संघाते' इत्येके । 'मृक्ष संघाते' । 'म्रक्ष' इत्येके । 'तक्ष ६६५ त्वचने' । त्वचनं संवरणं त्वचो ग्रहणं च । 'परिग्रहे' इत्येके । 'सूर्क्ष ६६६ आदरे' । सुषूर्क्ष । 'अनादरे' इति तु काचित्कोऽपपाठः । 'अवज्ञावहेलनमसूर्क्षणम्' इत्यमरः । 'काक्षि ६६७ वाक्षि ६६८ माक्षि ६६९ काङ्क्षायाम्'

'ध्राक्षि ६७० ध्राक्षि ६७१ ध्वाक्षि ६७२ घोरवासिते च' । 'चूष ६७३ पाने' । चुचूष । 'तूष ६७४ तुष्टौ' । 'पूष ६७५ वृद्धौ' । 'मूष ६७६ स्तेये' । 'लूष ६७७ रूष ६७८ भूषायाम्' । 'शूष ६७९ प्रसवे' । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः । 'यूष ६८० हिंसायाम्' । 'जूष ६८१ च' । 'भूष ६८२ अलंकारे' । भूषति । 'ऊष ६८३ रुजायाम्' । ऊषां चकार । 'ईष ६८४ उञ्छे' । 'कष ६८५ खष ६८६ शिष ६८७ जष ६८८ झष ६८९ शष ६९० वष ६९१ मष ६९२ रुष ६९३ रिष ६९४ हिंसार्थाः' । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठ्यादिः । चकाष । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ।

२३४० । तीषसहलुभरुषरिषः । ७ । २ । ४८ । इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् । रोषिता–रोष्टा । रोषिष्यति । रेषिता–रेष्टा । रेषिष्यति । 'भष ६९५ भर्त्सने' । इह भर्त्सनं श्वरवः । भषति । बभाष । 'उष ६९६ दाहे' । ओषति ।

२३४१ । उषविदजागृभ्योऽन्यतरस्याम् । ३ । १ । ३८ । एभ्यो लिट्याम्वा स्यात् । ओषां चकार । उवोष । ऊषतुः । उवोषिथ । 'जिषु ६९७ विषु ६९८ मिषु ६९९ सेचने' । जिजेष । क्रादिनियमादिट् । विवेषिथ । विवेषिव । वेष्टा । वेक्ष्यति । अविक्षत् । 'पुष ७०० पुष्टौ' । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्कृसु 'पुष्य' इति श्यना निर्देशादयं सेट् । अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् । 'श्रिषु ७०१ श्लिषु ७०२ प्रुषु ७०३ प्लुषु ७०४ दाहे' । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । 'अनिट्सु । दैवादिकस्यैव ग्रहणम्' इति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष । 'पृषु ७०५ वृषु ७०६ मृषु ७०७ सेचने' । 'मृषु' सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् । 'घृषु ७०८ संघर्षे' । 'हृषु ७०९ अलीके' । 'तुस ७१० ह्रस ७११ ह्लस ७१२ रस ७१३ शब्दे' । तुतोस । जह्रास । जह्लास । ररास । 'लस ७१४ श्लेषणक्रीडनयोः' । 'घस्लृ ७१५ अदने' । अयं न सार्वत्रिकः । 'लिट्यन्यतरस्याम्' (सू. २४२४) इत्यादेर्घस्लादेशविधानात् । ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । ऌदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धधातुके । क्रमरावि तु विशिष्योपादानम् । घसति । घस्ता ।

२३४२ । सः स्यार्धधातुके । ७ । ४ । ४९ । सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ।

२३४३ । पुषादिद्युताद्यॢदितः परस्मैपदेषु । ३ । १ । ५५ । श्यन्विकरणपुषादेर्द्युतादेर्ॢदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । अघसत् । 'जर्ज ७१६ चर्च ७१७ झर्झ ७१८ परिभाषणहिंसातर्जनेषु' । 'पिसृ ७१९ पेसृ ७२० गतौ' । पिपिसतुः । पिपेसतुः । 'हसे ७२१ हसने' । एदित्त्वान्न वृद्धिः । अहसीत् । 'णिश ७२२ समाधौ' । तालव्योष्मान्तः । प्रणेशति । 'मिश ७२३ मश ७२४ शब्दे रोषकृते च' । तालव्योष्मान्तौ । 'शव ७२५ गतौ' । दन्त्योष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत्–अशावीत् । 'शश ७२६ प्लुतगतौ' । तालव्योष्मान्तः । शशाश । शेशतुः । [illegible] हिंसायाम्' । दन्त्योष्मान्तः ।

'न शसदद-'(सू २२६३) इत्येत्त्वं न। शशसतुः। शशसुः। शशसिथ। 'शंसु ७२८ स्तु...' अयं दुर्गतावपीति दुर्गः। 'नृशंसो घातुकः क्रूरः' इत्यमरः। शशंस। आशिषि नलोपः... शस्यात्। 'चह ७२९ परिकल्कने'। कल्कनं शाठ्यम्। अचहीत्। 'मह ७३० पूजायाम्'... अमहीत्। 'रह ७३१ त्यागे'। 'रहि ७३२ गतौ'। रंहति। रंह्यात्। 'दृह ७३३ दृहि ७३४...' ७३५ बृहि ७३६ वृद्धौ'। दर्हति। ददर्ह। ददृहतुः। दृंहति। बर्हति। बृंहति। 'बृहि' शब्दे... 'बृंहितं करिगर्जितम्' इत्यमरः। 'बृहिर्' इत्येके। अबृहत्-अबर्हीत्। 'तुहिर् ७३७ दुहिर्...' उहिर् ७३९ अर्दने'। तोहति। तुतोह। अतुहत्-अतोहीत्। दोहति। अदुहत्-अदोहीत्... आनिङ्कारिकास्तस्य दुहेर्ग्रहणं नेच्छन्ति। ओहति। उवोह। ऊहतुः। ओहिता।... भवानूहत्। औहीत्। 'अर्ह ७४० पूजायाम्'। आनर्ह।

अथ कृपूपर्यन्ता अनुदात्तेतः। 'द्युत ७४१ दीप्तौ'। द्योतते।

२३४४। द्युतिस्वाप्योः संप्रसारणम्। ७। ४। ६७। अनयोरभ्यासस्य संप्रसारणं स्यात्। दिद्युते। दिद्युताते। द्योतिता।

२३४५। द्युद्भ्यो लुङि। १। ३। ९१। द्युतादिभ्यो लुङः परस्मैपदं वा स्यात्।... दिसूत्रेण परस्मैपदेऽङ्। अद्युतत्-अद्योतिष्ट। 'श्विता ७४२ वर्णे'। श्वेतते। शिश्विते।... अश्वितत्-अश्वेतिष्ट। 'ञिमिदा ७४३ स्नेहने'। मेदते।

२३४६। मिदेर्गुणः। ७। ३। ८२। मिदेरिको गुणः स्यादित्संज्ञकशकारादौ।... आदिशित्त्वाभावान्नानेन गुणः। मिमिदे। अमिदत्-अमेदिष्ट। 'ञिष्विदा ७४४ स्नेहन...' चनयोः'। 'मोहनयोः' इत्येके। स्वेदते। सिष्विदे। अस्विदत्-अस्वेदिष्ट। 'ञि...' च' इत्येके। अक्ष्विदत्-अक्ष्वेदिष्ट। 'रुच ७४५ दीप्तावभिप्रीतौ च'। रोचते सूर्यः।... रोचते भक्तिः'। अरुचत्-अरोचिष्ट। 'घुट ७४६ परिवर्तने'। घोटते। जुघुटे। अघुटत्-अघोटिष्ट। 'रुट ७४७ लुट ७४८ लुठ ७४९ प्रतिघाते'। अरुटत्-अरोटिष्ट। 'शुभ ७५० ...' 'क्षुभ ७५१ संचलने'। 'णभ ७५२ तुभ ७५३ हिंसायाम्'। आद्येऽभावेऽपि। 'नभन्ताम्... समे'। 'मा भूवन्नन्यके सर्वे' इति निरुक्तम्। अनभत्-अनभिष्ट। अतभत्-अतो... इमौ दिवादौ क्र्यादौ च। 'स्रंसु ७५४ ध्वंसु ७५५ भ्रंसु ७५६ अवस्रंसने'। 'ध्वंसु' गतौ... आङि न लोपः। अस्रसत्-अस्रंसिष्ट। 'नास्रसत्करिणां ग्रैवम्' इति रघुकाव्ये।... इत्यपि केचित्पेठुः। अत्र तृतीय एव तालव्यान्त इत्यन्ये। 'भ्रशु भ्रंशु अधःपतने' दिवादौ। 'स्रम्भु ७५७ विश्वासे'। अस्रभत्-अस्रम्भिष्ट। दन्त्यादिरयम्। तालव्या... प्रमादे गतः। 'वृतु ७५८ वर्तने'। वर्तते। ववृते।

२३४७। वृद्भ्यः स्यसनोः। १। ३। ९२। वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि...

२३४८। न वृद्भ्यश्चतुर्भ्यः। ७। २। ५९। एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्... नयोरभावे। वर्त्स्यति। वर्तिष्यते। अवृतत्। अवर्तिष्ट। अवर्त्स्यत्। अवर्तिष्यत्। '... वृद्धौ'। 'शृधु ७६० शब्दकुत्सायाम्'। इमौ वृतिवत्। 'स्यन्दू ७६१ प्रस्रवणे'। स्यन्दते... सस्यन्दे। सस्यन्दिषे-सस्यन्त्से। सस्यन्दिध्वे-सस्यन्द्ध्वे। स्यन्दिता-स्यन्ता।... स्यसनोः' (सू २३४७) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा... 'न वृद्भ्यः' (सू २३४८) इति निषेधः।... स्यन्दिष्यते-...

स्यन्दिषीष्ट–स्यन्त्सीष्ट । 'द्युद्भ्यो लुङि' (सू २३४९) इति परस्मैपदपक्षेऽङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट–अस्यन्त । अस्यन्त्साताम् । अस्यन्त्सत । अस्यन्त्स्यत् । अस्यन्दिष्यत–अस्यन्त्स्यत ।

२३४९ । अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु । ८ । ३ । ७२ । एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते–अनुस्यन्दते वा जलम् । 'अप्राणिषु' किम् । अनुस्यन्दते हस्ती । 'अप्राणिषु' इति पर्युदासात् 'मत्स्योदके अनुष्यन्दते' इत्यत्रापि पक्षे षत्वं भवत्येव । 'प्राणिषु न' इत्युक्तौ तु न स्यात् । 'कृपू ७६२ सामर्थ्ये' ।

२३५० । कृपो रो लः । ८ । २ । १८ । 'कृप' 'उः' इति छेदः । 'कृप' इति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेर्ऋकारस्यावयवो यो रो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चक्लृपे । चक्लृपिषे–चक्लृप्से इत्यादि स्यन्दिवत् ।

२३५१ । लुटि च क्लृपः । १ । ३ । ९३ । लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् ।

२३५२ । तासि च क्लृपः । ७ । २ । ६० । क्लृपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट–क्लृप्सीष्ट । अक्लृपत् । अकल्पिष्ट–अक्लृप्त । अकल्प्स्यत् । अकल्पिष्यत–अकल्प्स्यत । वृत् । वृत्तः संपूर्णो द्युतादिर्वृतादिश्चेत्यर्थः ।

अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । 'घट ७६३ चेष्टायाम्' । घटते । जघटे । 'घटादयो मितः' इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ 'मितां ह्रस्वः' (सू २५६८) इति 'चिण्णमुलोर्दीर्घोऽन्यतरस्याम्' (सू २७६२) इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि 'कमलवनोद्घाटनं कुर्वते ये' 'प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव' इत्यादि । शृणु । 'घट संघाते' इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । 'नान्ये मितोऽहेतौ' इति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । 'व्यथ ७६४ भयसंचलनयोः' । व्यथते ।

२३५३ । व्यथो लिटि । ७ । ४ । ६८ । व्यथोऽभ्यासस्य संप्रसारणं स्याल्लिटि । हलादिःशेषापवादः । थस्य हलादिःशेषेण निवृत्तिः । विव्यथे । 'प्रथ ७६५ प्रख्याने' । पप्रथे । 'प्रस ७६६ विस्तारे' । पप्रसे । 'म्रद ७६७ मर्दने' । 'स्खद ७६८ स्खदने' । स्खदनं विद्रावणम् । 'क्षजि ७६९ गतिदानयोः' । मित्त्वसामर्थ्यादनुपधात्वेऽपि 'चिण्णमुलोः–' (सू २७६२) इति दीर्घविकल्पः । अक्षाञ्जि–अक्षञ्जि । क्षञ्जं क्षञ्जम् । क्षाञ्जं क्षाञ्जम् । 'दक्ष ७७० गतिहिंसनयोः' । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः । 'क्रप ७७१ कृपायां गतौ च' । 'कदि ७७२ क्रदि ७७३ क्लदि ७७४ वैक्लव्ये' । 'वैकल्ये' इत्येके । 'त्रयोऽप्यनिदितः' इति नन्दी । 'इदितः' इति स्वामी । 'कदि क्रदी' इदितौ 'क्रद क्लद' इति चानिदिताविति मैत्रेयः । 'कदिक्रदिक्लदीनामाह्वानरोदनयोः' परस्मैपदिषूक्तानां पुनरिह पाठो मित्त्वार्थ आत्मनेपदार्थश्च । 'ञित्वरा ७७५ संभ्रमे' । 'घटादयः षितः' (ग सू १८६) । षित्त्वादङ् कृत्सु वक्ष्यते ।

अथ फणान्ताः परस्मैपदिनः । 'ज्वर ७७६ रोगे' । ज्वरति । जज्वार । 'गड ७७७ सेचने' । गडति । जगाड । 'हेड ७७८ वेष्टने' । 'हेडृ अनादरे' इत्यात्मनेपदिषु गतः स एवो-

त्सृष्टानुबन्धोऽनूद्यतेऽर्थविशेषे मित्त्वार्थम्। परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये
तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम्। हेडति। जिहेड। हिडयति। अहिडि-अहीडि। अना-
दरे तु हेडयति। 'वट ७७९ भट ७८० परिभाषणे'। 'वट वेष्टने' 'भट भृतौ' इति पठितयोः
परिभाषणे मित्त्वार्थोऽनुवादः। 'नट ७८१ नृत्तौ'। इत्थमेव पूर्वमपि पठितम्। तत्रायं विवेकः।
पूर्वं पठितस्य नाट्यमर्थः। यत्कारिषु नटव्यपदेशः। वाक्यार्थाभिनयो नाट्यम्। घटादौ तु
नृत्तं नृत्यं चार्थः। यत्कारिषु नर्तकव्यपदेशः। पदार्थाभिनयो नृत्यम्। गात्रविक्षेपमात्रं
नृत्तम्। केचित्तु घटादौ 'नट नतौ' इति पठन्ति। 'गतौ' इत्यन्ये। णोपदेशपर्युदासस्त्रे
भाष्यकृता 'नाटि' इति दीर्घपाठाद्घटादिर्णोपदेश एव। 'ष्टक ७८२ प्रतीघाते'। स्तकति।
'चक्र ७८३ तृप्तौ'। तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः।
आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम्। 'कखे ७८४ हसने'।
एदित्त्वान्न वृद्धिः। अकखीत्। 'रगे ७८५ शङ्कायाम्'। 'लगे ७८६ सङ्गे'। 'ह्रगे
७८७ ह्लगे ७८८ षगे ७८९ ष्टगे ७९० संवरणे'। 'कगे ७९१' नोच्यते। 'अस्यायमर्थः'
इति विशिष्य नोच्यते। क्रियासामान्यार्थत्वात्। अनेकार्थत्वादित्यन्ये। 'अक ७९२ अग
७९३ कुटिलायां गतौ'। 'कण ७९४ रण ७९५ गतौ'। चकाण। रराण। 'चण ७९६ शण
७९७ श्रण ७९८ दाने च'। 'शण गतौ' इत्यन्ये। 'श्रथ ७९९ श्लथ ८०० क्रथ ८०१ क्लथ
८०२ हिंसार्थाः'। 'जासिनिप्रहण-' (सू ६१७) इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते।
क्राथयति। मित्त्वं तु निपातनात्परत्वात्। 'चिण्णमुलोः-' (सू २७६२) इति दीर्घे चरितार्थम्।
अक्रथि-अक्राथि। क्रथं क्रथम्। क्राथं क्राथम्। 'वन ८०३ च'। हिंसायामिति शेषः।
वनु च नोच्यते। 'वनु' इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः। उदित्करणसामर्थ्यात्।
तने क्रियासामान्ये वनतीत्यादि। प्रवनयति। अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते।
'ज्वल ८०४ दीप्तौ'। णप्रत्ययार्थं पाठिष्यमाण एवायं मित्त्वार्थमनूद्यते। प्रज्वलयति। 'ह्वल ८०५
ह्मल ८०६ चलने'। प्रह्वलयति। प्रह्मलयति। 'स्मृ ८०७ आध्याने'। चिन्तायां पठिष्यमा-
णस्य आध्याने मित्त्वार्थोऽनुवादः। आध्यानमुत्कण्ठापूर्वकं स्मरणम्। 'दॄ ८०८ भये'।
'दॄ विदारणे' इति क्र्यादेरयं मित्त्वार्थोऽनुवादः। दृणन्तं प्रेरयति दरयति। भयादन्यत्र
दारयति। धात्वन्तरमेवेदमिति मते तु दरतीत्यादि। केचिद्घटादौ 'अत्स्मृदॄत्वर-' (सू २५६६)
इति सूत्रे च 'दॄ' इति दीर्घस्थाने ह्रस्वं पठन्ति तन्नेति माधवः। 'नॄ ८०९ नये'। क्र्यादौ
पाठिष्यमाणस्यानुवादः। नयादन्यत्र नारयति। 'श्रा ८१० पाके'। 'श्रै' इति कृतात्वस्य
इत्यदादिकस्य च सामान्येनानुकरणम्। 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य' (प ९३)
'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (प ११४) इति परिभाषाभ्याम्
श्रपयति विक्लेदयतीत्यर्थः। पाकादन्यत्र श्रापयति। स्वेदयतीत्यर्थः। 'मारणतोषणनिशा-
नेषु ज्ञा ८११'। 'निशामनं चाक्षुषज्ञानम्' इति माधवः। ज्ञापनमात्रम्' इत्यन्ये। 'निशा-
नेषु' इति पाठान्तरम्। निशानं तीक्ष्णीकरणम्। एष्वेवार्थेषु जानातिर्मित्। 'ज्ञप मिच्च'
इति चुरादौ। ज्ञापनं मारणादिकं च तस्यार्थः। कथं 'विज्ञापना भर्तृषु सिद्धिमेति'
'तज्ज्ञापयत्याचार्यः' इति च। शृणु। माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात्। ज्ञापनमात्रे
मित्त्वमिति मते तु 'ज्ञा नियोगे' इति चौरादिकस्य। धातूनामनेकार्थत्वात्। निशानेषु

पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः। 'कम्पने चलिः ८१२'। 'चल कम्पने' इति ज्वलादिः। चलयति शाखाम्। कम्पनादन्यत्र तु शीलं चालयति। अन्यथा करोतीत्यर्थः। 'हरतीत्यर्थः' इति स्वामी। सूत्रं चालयति। क्षिपतीत्यर्थः। 'छदिर् ८१३ ऊर्जने'। 'छद अपवारणे' इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः। अनेकार्थत्वादूर्जेऽर्थे वृत्तिः। छदन्तं प्रयुङ्क्ते छदयति। बलवन्तं प्राणवन्तं वा करोतीत्यर्थः। अन्यत्र छादयति। अपवारयन्तं प्रयुङ्क्ते इत्यर्थः। स्वार्थे णिचि तु छादयति। बलीभवति प्राणीभवति। अपवारयति वेत्यर्थः। 'जिह्वोन्मथने लडिः ८१४'। 'लड विलासे' इति पठितस्य मित्त्वार्थोऽनुवादः। उन्मथनं ज्ञापनम्। जिह्वाशब्देन षष्ठीतत्पुरुषः। लडयति जिह्वाम्। तृतीयातत्पुरुषो वा। लडयति जिह्वया। अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते। समाहारद्वन्द्वोऽयम्। लडयति शत्रुम्। लडयति दधि। अन्यत्र लाडयति पुत्रम्। 'मदी ८१५ हर्षग्लेपनयोः'। ग्लेपनं दैन्यम्। दैवादिकस्य मित्त्वार्थोऽयमनुवादः। मदयति। हर्षयति। ग्लेपयति वेत्यर्थः। अन्यत्र मादयति। चित्तविकारमुत्पादयतीत्यर्थः। 'ध्वन ८१६ शब्दे'। भाव्ययं मित्त्वार्थमनूद्यते। ध्वनयति घण्टाम्। अन्यत्र ध्वानयति। अस्पष्टाक्षरमुच्चारयतीत्यर्थः। अत्र भोजः 'दलिवलिस्खलिरणिध्वनित्रपिक्षपयश्च' इति पपाठ। तत्र 'ध्वनिरणी' उदाहृतौ। 'दल विशरणे'। 'वल संवरणे' 'स्खल संचलने' 'त्रपूष् लज्जायाम्' इति गताः। तेषां णौ दलयति। वलयति। स्खलयति। त्रपयति। 'क्षै क्षये' इति वक्ष्यमाणस्य कृतात्वस्य पुका निर्देशः। क्षपयति। 'स्वन ८१७ अवतंसने'। शब्द इति पठिष्यमाणस्यानुवादः। स्वनयति। अन्यत्र स्वानयति। 'घटादयो मितः' (ग सू १८७)। मित्संज्ञा इत्यर्थः। 'जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' (ग सू १८८)। 'मितः' इत्यनुवर्तते। 'जॄष्' इति षित्वनिर्देशाज्जीर्यतेर्ग्रहणम्। जृगातेस्तु जारयति। केचित्तु 'जनीजॄष्णसु—' इति पठित्वा 'ष्णसु निरसने' इति दैवादिकमुदाहरन्ति। 'ज्वलह्वलह्मलनमामनुपसर्गाद्वा' (ग सू १८९)। एषां मित्त्वं वा। प्राप्तविभाषेयम्। ज्वलयति–ज्वालयति। उपसृष्टे तु नित्यं मित्त्वम्। प्रज्वलयति। कथं तर्हि प्रज्वालयति। उन्नामयतीति। घञन्तात् 'तत्करोति–' इति णौ। कथं संक्रामयतीति। 'मितां ह्रस्वः' (सू २५६८) इति सूत्रे 'वा चित्तविरागे' (सू २६०९) इत्यतो 'वा' इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वृत्तिकृत्। एतेन 'रजो विश्रामयन्राज्ञां' 'धुर्यान्विश्रामयेति सः' इत्यादि व्याख्यातम्। 'ग्लास्नावनुवमां च' (ग सू १९०)। अनुपसर्गादेषां मित्त्वं वा स्यात्। आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा। 'न कम्यमिचमाम्' (ग सू १९१)। अमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात्। कामयते। आमयति। चामयति। 'शमो ८१८ दर्शने' (ग सू १९२)। शाम्यतिर्दर्शने मिन्न स्यात्। निशामयति रूपम्। अन्यत्र तु 'प्रणयिनो निशमय्य वधूकथाः'। कथं तर्हि 'निशामय तदुत्पत्तिं विस्तराद्गदतो मम' इति। 'शम आलोचने' इति चौरादिकस्य धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः। शाम्यतिवत्। 'यमो ८१९ अपरिवेषणे' (ग सू १९३)। यच्छतिर्भोजनतोऽन्यत्र मिन्न स्यात्। आयामयति। द्राघयति। व्यापारयति वेत्यर्थः। परिवेषणे तु। यमयति ब्राह्मणान्। भोजयतीत्यर्थः। 'पर्यवसितं नियमयन्' इत्यादि तु नियमवच्छब्दात्तत्करोतीति णौ बोध्यम्। 'स्खदिर् ८२० अवपरिभ्यां च' (ग सू १९४)। मिन्नेत्येव। अवस्खादयति। परिस्खादयति। 'अपावपरिभ्यः' इति न्यासकारः। स्वामी तु 'न कमि–'

इति नञमुत्तरत्रिसूत्र्यामननुवर्त्य 'शमः अदर्शने' इति चिच्छेद । यमस्तु 'अपरिवेषणे' मित्त्वमाह । तन्मते 'पर्यवसितं नियमयन्' इत्यादि सम्यगेव । 'उपसृष्टस्य स्वदेश्चेदवादि-भ्यस्य' इति नियमात्प्रस्खादयतीत्याह । तस्मात्तत्रद्वय उदाहरणप्रत्युदाहरणयोर्व्यत्यासः फलितः इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् । 'फण ८२१ गतौ' । 'न' इति निषे-धमसंभवात् । निषेधात्पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् ।

२३९४ । फणां च सप्तानाम् । ६ । ४ । १२५ । एषां वा एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फणिथ । पफणतुः । पफणुः । फणयति । 'वृत्' । घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फाणयतीत्येव । 'राजृ ८२२ दीप्तौ' । 'स्वरितेत्' । राजति-राजते । रेजतुः-रराजतुः । रेजे-रराजे । 'अतः' इत्यनुवृत्तावारं-विधानसामर्थ्यादात एत्वम् । 'टुभ्राजृ ८२३ टुभ्राशृ ८२४ टुभ्लाशृ ८२५ दीप्तौ' । अनुदात्तेतः । भ्राजेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु भ्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्या-त्फणादेरेव ग्रहणम् । भ्रेजे-बभ्राजे । 'वा भ्राश-' (सू २३२१) इति श्यन्वा । भ्राश्यते-भ्राशते । भ्रेशे-बभ्राशे । भ्लाशते भ्लाश्यते । भ्लेशे-बभ्लाशे । द्वावपीमौ तालव्यान्तौ । 'स्यमु ८२६ स्वन ८२७ ध्वन ८२८ शब्दे' । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः-सस्यमतुः । अस्यमीत् । स्वेनतुः-सस्वनतुः । सस्वनुः । अस्वानीत्-अस्वनीत् । विष्वणति । अवष्वणति सशब्दं भुङ्क्त इत्यर्थः । 'वेश्च स्वनः-' (सू २२७४) इति षत्वम् । फणादयो गताः । दध्वनतुः । 'षम ८२९ ष्टम ८३० अवैकल्ये' । ससाम । तस्ताम । 'ज्वल ८३१ दीप्तौ' 'अतो ल्रान्तस्य' (सू २३३०) । अज्वालीत् । 'चल ८३२ कम्पने' । 'जल ८३३ घातने' । घातनं तैक्ष्ण्यम् । 'टल ८३४ ट्वल ८३५ वैक्लव्ये' । 'ष्ठल ८३६ स्थाने' । 'हल ८३७ विलेखने' । 'णल ८३८ गन्धे' । 'बन्धने' इत्येके । 'पल ८३९ गतौ' । पलति । 'बल ८४० प्राणने धान्यावरोधे च' । बलति । बेलतुः । बेलुः । 'पुल ८४१ महत्त्वे' । पोलति । 'कुल ८४२ संस्त्याने बन्धुषु च' । संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल । 'शल ८४३ हुल ८४४ पत्लृ ८४५ गतौ' । शशाल । जुहोल । पपात । पेततुः । पतिता ।

२३९५ । पतः पुम् । ७ । ४ । १९ । अङि परे । अपप्तत् । 'नेर्गद-' (सू२२८५) इति णत्वम् । प्रण्यपप्तत् । 'क्वथे ८४६ निष्पाके' । क्वथति । चक्वाथ । अक्वथीत् । 'पथे ८४७ गतौ' । अपथीत् । 'मथे ८४८ विलोडने' । मेथतुः । अमथीत् । 'टुवम् ८४९ उद्गिरणे' । इत्त्वं निपातनात् ऋतः इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्वादेत्त्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् । 'भ्रमु ८५० चलने' । 'वा भ्राश-' (सू २३२१) इति श्यन्वा । भ्रम्यति-भ्रमति । 'भ्राम्यति' इति तु दिवादेर्वक्ष्यते ।

२३९६ । वा जॄभ्रमुत्रसाम् । ६ । ४ । १२४ । एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः-बभ्रमतुः । अभ्रमीत् । 'क्षर ८५१ संचलने' । अक्षारीत् ।

अथ द्वावनुदात्तेतौ । 'षह ८५२ मर्षणे' । 'परिनिविभ्यः-' (सू २२७५) इति षत्वम् । परिषहते । सेहे । सहिता । 'तीषसह-' (सू २३४०) इति वा इट् । इडभावे ढत्वधत्व-ष्टुत्वढलोपाः ।

२३९७ । सहिवहोरोदवर्णस्य । ६ । ३ । ११२ । अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ।

२३५८ । सोढः । ८ । ३ । ११५ । सोढ्रूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ।

२३५९ । सिवादीनां वाड्व्यवायेऽपि । ८ । ३ । ७१ । परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यषहत पर्यसहत । 'रमु ८५३ क्रीडायाम्' । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ।

अथ कसन्ताः परस्मैपदिनः । 'षद्लृ ८५४ विशरणगत्यवसादनेषु' ।

२३६० । पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः । ७ । ३ । ७८ । पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ-ससत्थ । सत्ता । सत्स्यति । लृदित्त्वादङ् । असदत् । 'सदिरप्रतेः' (सू २२७१) । निषीदति । न्यषीदत् ।

२३६१ । सदेः परस्य लिटि । ८ । ३ । ११८ । सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः । 'शद्लृ ८५५ शातने' । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ।

२३६२ । शदेः शितः । १ । ३ । ६० । शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ-शशत्थ । शत्ता । अशदत् । 'क्रुश ८५६ आह्वाने रोदने च' । क्रोशति । क्रोष्टा । क्लेः क्सः । अक्रुक्षत् । 'कुच ८५७ संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच । 'बुध ८५८ अवगमने' । बोधति । बोधिता । बोधिष्यति । 'रुह ८५९ बीजजन्मनि प्रादुर्भावे च' । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् । 'कस ८६० गतौ' । अकासीत्-अकसीत् । वृत् । ज्वलादिगणः समाप्तः ।

अथ गूहत्यन्ताः स्वरितेतः । 'हिक्क ८६१ अव्यक्ते शब्दे' । हिक्कति-हिक्कते । 'अञ्चु ८६२ गतौ याचने च' । अञ्चति-अञ्चते । 'अचु' इत्येके । 'अचि' इत्यपरे । 'टुयाचृ ८६३ याच्ञायाम्' । याचति-याचते । 'रेटृ ८६४ परिभाषणे' । रेटति । रेटते । 'चते ८६५ चदे ८६६ याचने' । चचात । चेते । अचतीत् । चचाद । चेदे । अचदीत् । 'प्रोथृ ८६७ पर्याप्तौ' । पुप्रोथ । पुप्रोथे । 'मिदृ ८६८ मेदृ ८६९ मेधाहिंसनयोः' । मिमेद । मिमेदे । 'थान्ताविमौ' इति स्वामी । मिमेथ । 'धान्तौ' इति न्यासः । 'मेधृ ८७० संगमे च' । मेधति । मिमेधे । 'णिदृ ८७१ णेदृ ८७२ कुत्सासंनिकर्षयोः' । निनेद । निनिदतुः । निनेदे । 'शृधु ८७३ मृधु ८७४ उन्दने' । उन्दनं क्लेदनम् । शर्धति-शर्धते । शर्धिता । मर्धति-मर्धते । 'बुधिर् ८७५ बोधने' । बोधति-बोधते । इरित्त्वादङ्वा । अबुधत्-अबोधीत्-अबोधिष्ट । 'दीपजन-' (सू २३२८) इति चिण्तु न भवति पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् । 'उबुन्दिर् ८७६ निशामने' । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् । 'वेणृ ८७७ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु' । वेणति-वेणते । नान्तोऽप्ययम् । 'खनु ८७८ अवदारणे' । खनति-खनते ।

२३६३ । गमहनजनखनघसां लोपः क्ङित्यनङि । ६ । ४ । ९८ । एषामुपधाया लोपः स्यादजादौ क्ङिति न त्वङि । चख्नतुः । 'ये विभाषा' (सू २३१९) । खायात्-खन्यात् । 'चीवृ ८७९ आदानसंवरणयोः' । चिचीव-चिचीवे । 'चायृ ८८० पूजानिशामनयोः' । 'व्यय ८८१ गतौ' । अव्ययीत् । 'दाशृ ८८२ दाने' । ददाश-ददाशे । 'भेषृ ८८३ भये' ।

'गतौ' इत्येके । भेषति-भेषते । 'भ्रेषृ ८८४ भ्लेषृ ८८५ गतौ' । 'अस ८८६ गतिदीप्त्यादानेषु' । असति-असते । आस-आसे । अयं षान्तोऽपि । 'स्पश ८८७ बाधनस्पर्शनयोः' । स्पर्शनं ग्रथनम् । स्पशति-स्पशते । 'लष ८८८ कान्तौ' । 'भ्राश-'(सू २३२१) इति श्यन्वा । लष्यति-लषति । लेषे । 'चष ८८९ भक्षणे' । 'छष ८९० हिंसायाम्' । चच्छषतुः । चच्छषे । 'झष ८९१ आदानसंवरणयोः' । 'भ्रक्ष ८९२ भ्लक्ष ८९३ अदने' । 'भक्ष' इति मैत्रेयः । 'दासृ ८९४ दाने' । 'माहृ ८९५ माने' । 'गुहू ८९६ संवरणे' ।

२३६४ । ऊदुपधाया गोहः । ६ । ४ । ८९ । गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति-गूहते । ऊदित्त्वादिड्वा । गूहिता-गोढा । गूहिष्यति-घोक्ष्यति । गूह्यात् । अगूहीत् । इडभावे क्सः । अघुक्षत् ।

२३६५ । लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । ७ । ३ । ७३ । एषां क्सस्य लुक् स्याद्दन्त्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । 'क्सस्याचि' (सू २३३६) इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि-अघुक्षावहि । अघुक्षामहि ।

अथाजन्ता उभयपदिनः । 'श्रिञ् ८९७ सेवायाम्' । श्रयति-श्रयते । शिश्रियतुः । श्रयिता । 'णिश्रि-' (सू २३१२) इति चङ् । अशिश्रियत् । 'भृञ् ८९८ भरणे' । भरति । बभार । बभ्रतुः । बभर्थ । बभृव । बभृषे । भर्ता ।

२३६६ । ऋद्धनोः स्ये । ७ । २ । ७० । ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ।

२३६७ । रिङ् शयग्लिङ्क्षु । ७ । ४ । २८ । शे यकि यादावार्धधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ।

२३६८ । उश्च । १ । २ । १२ । ऋवर्णात्परौ झलादी लिङ्सिचौ तङ्परौ कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ।

२३६९ । ह्रस्वादङ्गात् । ८ । २ । २७ । सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् । 'हृञ् ८९९ हरणे' । हरणं प्रापणं स्वीकारः स्तेयं नाशनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति । 'धृञ् ९०० धारणे' । धरति । अधार्षीत् । अधृत । 'णीञ् ९०१ प्रापणे' । निनयिथ । निन्यिषे ।

अथाजन्ताः परस्मैपदिनः । 'धेट् ९०२ पाने' । धयति ।

२३७० । आदेच उपदेशेऽशिति । ६ । १ । ४५ । उपदेशे एजन्तस्य धातोरात् स्यान्न तु शिति ।

२३७१ । आत औ णलः । ७ । १ । ३४ । आदन्ताद्धातोर्णल औकारादेशः स्यात् ।

२३७२ । आतो लोप इटि च । ६ । ४ । ६४ । अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते 'द्विर्वचनेऽचि' (सू २२४३) इति निषेधे द्वित्वे कृत आलोपः । दधतुः । दधुः । दधिथ-दधाथ । दधिव । दधिम । धाता ।

२३७३ । दाधा घ्वदाप् । १ । १ । २० । दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ।

२३७४ । एर्लिङि । ६ । ४ । ६७ । घुसंज्ञानां मास्थादीनां चैत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ।

२३७५। विभाषा धेट्श्व्योः। ३। १। ४९। आभ्यां च्लेश्चङ् स्यात्कर्तृवाचिनि लुङि परे। 'चङि' (सू २३१५) इति द्वित्वम्। अदधत्। अदधताम्।

२३७६। विभाषा घ्राधेट्शाच्छासः। २। ४। ७८। एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे। अधात्। अधाताम्। अधुः।

२३७७। यमरमनमातां सक्च। ७। २। ७३। एषां सक्स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु। अधासीत्। अधासिष्टाम्। अधासिषुः। 'ग्लै ९०३ म्लै ९०४ हर्षक्षये'। हर्षक्षयो धातुक्षयः। ग्लायति। जग्लौ। जग्लिथ-जग्लाथ।

२३७८। वान्यस्य संयोगादेः। ६। ४। ६८। घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि। ग्लायात्-ग्लेयात्। अग्लासीत्। म्लायति। 'द्यै ९०५ न्यक्करणे'। न्यक्करणं तिरस्कारः। 'द्रै ९०६ स्वप्ने'। 'ध्रै ९०७ तृप्तौ'। 'ध्यै ९०८ चिन्तायाम्'। 'रै ९०९ शब्दे'। 'स्त्यै ९१० ष्ट्यै ९११ शब्दसंघातयोः'। स्त्यायति। षोपदेशस्यापि सत्वे कृते रूपं तुल्यम्। षोपदेशफलं तु तिष्ट्यासति अतिष्टचपदित्यत्र षत्वम्। 'खै ९१२ खदने'। 'क्षै ९१३ जै ९१४ षै ९१५ क्षये'। क्षायति। जजौ। ससौ। साता। 'घुमास्था-' (सू २४६२) इत्यत्र 'विभाषा घ्राधेट्-' (सू २३७६) इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य। तेन एत्वसिज्लुकौ न। सायात्। असासीत्। 'कै ९१६ गै ९१७ शब्दे'। गेयात्। अगासीत्। 'शै ९१८ श्रै ९१९ पाके'। 'पै ९२० ओवै ९२१ शोषणे'। पायात्। अपासीत्। 'घुमास्था-' (सू २४६२) इतीत्वं तदपवाद 'एर्लिङि' (सू २३७४) इत्येत्वम् 'गातिस्था-' (सू २२२३) इति सिज्लुक् च, न। पारूपस्य लाक्षणिकत्वात्। 'ष्टै ९२२ वेष्टने'। स्तायति। 'ष्णै ९२३ वेष्टने'। 'शोभायां च' इत्येके। स्नायति। 'दैप् ९२४शोधने'। दायति। अघुत्वादित्वसिज्लुकौ न। दायात्। अदासीत्। 'पा ९२५ पाने'। 'पाघ्राध्मा-' (सू २३६०) इति पिबादेशः। तस्यादन्तत्वान्नोपधागुणः। पिबति। पेयात्। अपात्। 'घ्रा ९२६ गन्धोपादाने'। जिघ्रति। घ्रायात्-घ्रेयात्। अघ्रासीत्। अघ्रात्। 'ध्मा ९२७ शब्दाग्निसंयोगयोः'। धमति। 'ष्ठा ९२८ गतिनिवृत्तौ'। तिष्ठति। 'स्थादिष्वभ्यासेन-' (सू २२७७) इति षत्वम्। अधितष्ठौ। 'उपसर्गात्-' (सू २२७०) इति षत्वम्। अधिष्ठाता। स्थेयात्। 'म्ना ९२९ अभ्यासे'। मनति। 'दाण् ९३० दाने'। प्रणियच्छति। देयात्। अदात्। 'ह्वृ ९३१ कौटिल्ये'। ह्वरति।

२३७९। ऋतश्च संयोगादेर्गुणः। ७। ४। १०। ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि। किदर्थमपीदं परत्वाण्णल्यपि भवति। रपरत्वम्। उपधावृद्धिः। जह्वार। जह्वरतुः। जह्वरुः। जह्वर्थ। ह्वर्ता। 'ऋद्धनोः स्ये' (स २३६६)। ह्वरिष्यति।

२३८०। गुणोऽर्तिसंयोगाद्योः। ७। ४। २९। अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वार्ष्टाम्। 'स्वृ ९३२ शब्दोपतापयोः'। 'स्वरतिसूति-' (सू २२७९) इति वेट्। सस्वरिथ-सस्वर्थ। वमयोस्तु

२३८१। श्र्युकः किति। ७। २। ११। श्रिञ एकाच उगन्ताच्च परयोर्गित्कितोरिण्न स्यात्। परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट्। सस्वरिव। सस्वरिम। परत्वात् 'ऋद्धनोः स्ये' (सू २३६६)

इति नित्यमिट् । स्वरिष्यति । स्वर्यात् । आस्वारीत् । अस्वारिष्टाम् । अस्वार्षीत् । अस्वा-र्ष्टाम् । 'स्मृ ९३३ चिन्तायाम्' । 'ह्वृ ९३४ संवरणे' । 'सृ ९३५ गतौ' । क्रादिनियमादिट् । ससर्थ । ससृव । रिङ् । स्रियात् । असार्षीत् । असार्ष्टाम् ।

२३८२ । सर्तिशास्त्यर्तिभ्यश्च । ३ । १ । ५६ । एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि । शा लुक्शपा शासिना साहचर्यात् 'सर्त्यर्ती' जौहोत्यादिकावेव गृह्येते । तेन भ्वाद्योर्नाङ् । शीघ्र-गतौ तु 'पाघ्राध्मा-' (सू २३६०) इति शिति धौरादेशः । धावति । 'ऋ ९३६ गतिप्रा-पणयोः' । ऋच्छति ।

२३८३ । ऋच्छत्यृताम् । ७ । ४ । ११ । तौदादिकऋच्छेर्ऋधातोर्ऋतां च गुणः स्याल्लि-टि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ।

२३८४ । इडत्त्यर्तिव्ययतीनाम् । ७ । २ । ६६ । 'अद्' 'ऋ' 'व्येञ्' एभ्यस्थलो नित्य-मिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् । 'गृ ९३७ घृ ९३८ सेचने' । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् । 'ध्वृ ९३९ हूर्छने' । 'स्रु ९४० गतौ' । सुस्रोथ । सुस्रुव । स्रूयात् । 'णिश्रि-' (सू २३१२) इति चङ् लघूपधगुणादन्तरङ्गत्वादुवङ् । असुस्रुवत् । 'षु ९४१ प्रसवैश्वर्ययोः' । प्रसवोऽभ्यनुज्ञानम् सुषोथ-सुषविथ । सुषुविव । सोता ।

२३८५ । स्तुसुधूञ्भ्यः परस्मैपदेषु । ७ । २ । ७२ । एभ्यः सिच इट् स्यात्परस्मै-पदेषु । असावीत् । पूर्वोत्तराभ्यां ञिद्भ्यां साहचर्यात्सुनोतेरेव ग्रहणमिति पक्षे असौषीत् । 'श्रु ९४२ श्रवणे' ।

२३८६ । श्रुवः शृ च । ३ । १ । ७४ । श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शपोऽप-वादः । श्नोर्ङित्त्वाद्धातोर्गुणो न । शृणोति । शृणुतः ।

२३८७ । हुश्नुवोः सार्वधातुके । ६ । ४ । ८७ । जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण्स्यादजादौ सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः-शृणुवः । शृण्मः-शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् अश्रौषीत् । 'ध्रु ९४३ स्थैर्ये' । ध्रवति । अयं कुटादौ गत्यर्थोऽपि । 'दु ९४४ द्रु ९४५ गतौ' दुदोथ-दुदविथ । दुदुविव । दुद्रोथ । दुद्रुव । 'णिश्रि-' (सू २३१२) इति चङ् । अदुद्रुवत् 'जि ९४६ ज्रि ९४७ अभिभवे' । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये सकर्मकः शत्रूञ्जयति । द्वितीये त्वकर्मकः । 'अध्ययनात्पराजयते' । अध्येतुं ग्लायतीत्यर्थः 'विपराभ्यां जेः' (सू २६८५) इति तङ् । 'पराजेरसोढः' (सू ५८९) इत्यपादानत्वम् ।

अथ डीङन्ता ङितः । 'ष्मिङ् ९४८ ईषद्धसने' । स्मयते । सिष्मिये । सिष्मियिढ्वे-सिष्मियिध्वे । 'गुङ् ९४९ अव्यक्ते शब्दे' । गवते । जुगुवे । 'गाङ् ९५० गतौ' । गाते गाते । गाते । इट एत्वे कृते वृद्धिः । गै । लङ इटि । अगे । गेत । गेयाताम् । गेत् गासीष्ट । 'गाङ्कुटादिभ्यः-' (सू २४६१) इति सूत्र इङादेशस्यैव गाङो ग्रहणं न त्वस्य तेनाङित्त्वात् 'घुमास्था-' (सू २४६२) इतीत्त्वं न । अगास्त । अदादिकोऽयमिति हरद-दयः । फले तु न भेदः । 'कुङ् ९५१ घुङ् ९५२ उङ् ९५३ ङुङ् ९५४ शब्दे' । अन्ये 'टङ् कुङ् खुङ् गुङ् घुङ् ङुङ्' इत्याहुः । कवते । चुकुवे । घवते । अवते । ऊवे । 'वार्णादे

बलीयः' (५९६) इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औट । ङवते । ञुङुवे । ङोता । 'च्युङ् ९५५ ज्युङ् ९५६ प्रुङ् ९५७ प्लुङ् ९५८ गतौ' । 'क्लुङ्' इत्येके । 'रुङ् ९५९ गतिरेषणयोः' । रेषणं हिंसा । रुरुवे । रवितासे' । धृङ् ९६० अवध्वंसने' । धरते । दध्रे । 'मेङ् ९६१ प्रणिदाने' । प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । 'नेर्गद–' (सू २२८५) इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्रकृतेरपि ग्रहणस्येष्टत्वात् । 'देङ् ९६२ रक्षणे' । दयते ।

२३८८ । दयतेर्दिगि लिटि । ७ । ४ । ९ । 'दिग्यादेशेन द्वित्वबाधनमिष्यते' इति वृत्तिः । दिग्ये ।

२३८९ । स्थाघ्वोरिच्च । १ । २ । १७ । अनयोरिदादेशः स्यात् सिच्च कित्स्यात् । अदित । अदिथाः । अदिषि । 'श्यैङ् ९६३ गतौ' । श्यायते । शश्ये । 'प्यैङ् ९६४ वृद्धौ' । प्यायते । पप्ये । प्याता । 'त्रैङ् ९६५ पालने' । त्रायते । तत्रे । 'पूङ् ९६६ पवने' । पवते । पुपुवे । पविता । 'मूङ् ९६७ बन्धने' । मवते । 'डीङ् ९६८ विहायसा गतौ' । डयते । डिड्ये । डयिता । 'तॄ ९६९ प्लवनतरणयोः' ।

२३९० । ॠत इद्धातोः । ७ । १ । १०० । ॠदन्तस्य धातोरङ्गस्य इत्स्यात् । 'इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा ४३७३) । तरति । 'ऋच्छत्यॄताम्' (सू २३८३) इति गुणः । 'तॄफल–' (सू २३०१) इत्येत्त्वम् । तेरतुः । तेरुः ।

२३९१ । वृतो वा । ७ । २ । ३८ । वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि । तरीता–तरिता । 'अलिटि' इति किम् । तेरिथ । 'हलि च' (सू ३५४) इति दीर्घः । तीर्यात् ।

२३९२ । सिचि च परस्मैपदेषु । ७ । २ । ४० । अत्र वृत इटो दीर्घो न । अतारिष्टाम् ।

अथाष्टावनुदात्तेतः । 'गुप ९७० गोपने' । 'तिज ९७१ निशाने' । 'मान ९७२ पूजायाम्' । 'बध ९७३ बन्धने' ।

२३९३ । गुप्तिज्किद्भ्यः सन् । ३ । १ । ५ ।

२३९४ । मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य । ३ । १ । ६ । सूत्रद्वयोक्तेभ्यः सन्स्यात् मानादीनामभ्यासस्येकारस्य दीर्घश्च । 'गुपेर्निन्दायाम्' (वा १६८७) । 'तिजेः क्षमायाम्' (वा १६८८) । 'कितेर्व्याधिप्रतीकारे' (वा १६८९) । 'निग्रहे' 'अपनयने' 'नाशने' 'संशये च' । 'मानेर्जिज्ञासायाम्' (वा १६९२) । 'बधेश्चित्तविकारे' (वा १६९३) । 'दानेरार्जवे' (वा १६९४) । 'शानेर्निशाने' (वा १६९५) । 'सनाद्यन्ताः–' (सू २३०४) इति धातुत्वम् ।

२३९५ । सन्यङोः । ६ । १ । ९ । सन्नन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतो दानशानौ च स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरे त्वनुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेड्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मी-

मांसते । भष्भावः । चर्व्वम् । बीभत्सते । 'रभ ९७४ राभस्ये' । आरभते । आरेभे । रब्धा । रप्स्यते । 'डुलभष् ९७५ प्राप्तौ' । लभते । 'ष्वञ्ज ९७६ परिष्वङ्गे' ।

२३९६ । दंशसञ्जस्वञ्जां शपि । ६ । ४ । २५ ।

२३९७ । रञ्जेश्च । ६ । ४ । २६ । एषां शपि नलोपः । स्वजते । परिष्वजते । 'श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वा' इति व्याकरणान्तरम् । 'देभतुः' 'सस्वजे' इति भाष्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते । 'सदेः परस्य लिटि' (सू २२६१) इति सूत्रे 'स्वञ्जेरुपसंख्यानम्' (वा ४९६८) । अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे-परिषस्वञ्जे । सस्वजिषे-सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । 'प्राक्सितात्-' (सू २२७६) इति षत्वम् । परिनिविभ्यस्तु 'सिवादीनां वा-' (सू २३५९) इति विकल्पः । एतदर्थमेव 'उपसर्गात्सुनोति-' (सू २२७०) इत्येव सिद्धे स्तुस्वञ्ज्योः 'परिनिवि-' (सू २२७५) इत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त-पर्यस्वङ्क्त । 'हद ९७७ पुरीषोत्सर्गे' । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ।

अथ परस्मैपदिनः । 'ञिक्ष्विदा ९७८ अव्यक्ते शब्दे' । 'स्कन्दिर् ९७९ गतिशोषणयोः' । चस्कन्दिथ-चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्त्वादङ्वा । अस्कदत्-अस्कान्त्सीत् । अस्कान्ताम् । अस्कान्त्सुः ।

२३९८ । वेः स्कन्देरनिष्ठायाम् । ८ । ३ । ७३ । षत्वं वा स्यात् । कृत्यैवेदम् । 'अनिष्ठायाम्' इति पर्युदासात् । विष्कन्ता-विस्कन्ता । निष्ठायां तु विस्कन्नः ।

२३९९ । परेश्च । ८ । ३ । ७४ । अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागात् 'अनिष्ठायाम्' इति न संबध्यते । परिष्कन्दति-परिस्कन्दति । परिस्कन्नः-परिष्कण्णः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । 'धातूपसर्गयोः कार्यमन्तरङ्गम्' इत्यभ्युपगमात् । 'पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेन' इति भाष्यम् । 'पूर्वं साधनेन-' इति मतान्तरे तु न णत्वम् । 'यभ ९८० मैथुने' । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् । 'णम ९८१ प्रह्वत्वे शब्दे च' । नेमिथ-ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् । 'गम्लृ ९८२ सृप्लृ ९८३ गतौ' ।

२४०० । इषुगमियमां छः । ७ । ३ । ७७ । एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ-जगन्थ । गन्ता ।

२४०१ । गमेरिट् परस्मैपदेषु । ७ । २ । ५८ । गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । 'अनङि' इति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । सर्प ।

२४०२ । अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । ६ । १ । ५९ । उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता-सर्प्ता । स्रप्स्यति-सर्प्स्यति । असृपत् । 'यम ९८४ उपरमे' । यच्छति । येमिथ-ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् । 'तप ९८५ संतापे' । तप्ता । अताप्सीत् ।

२४०३ । निसस्तपतावनासेवने । ८ । ३ । १०२ । षः स्यात् । आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्विषये । निष्टपति । 'त्यज ९८६ हानौ' । तत्याजिथ-तत्यक्थ ।

त्यक्ता । अत्याक्षीत् । 'षञ्ज ९८७ सङ्गे' । 'दंशसञ्जस्वञ्जां शपि' (सू २३९६) इति नलोपः । सजति । सङ्क्ता । 'दृशिर् ९८८ प्रेक्षणे' । पश्यति ।

२४०४ । विभाषा सृजिदृशोः । ७ । २ । ६५ । आभ्यां थल इड्वा ।

२४०५ । सृजिदृशोर्झल्यमकिति । ६ । १ । ५८ । अनयोरमागमः स्याज्झलादावकिति । ददृष्ठ–ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ।

२४०६ । ऋदृशोऽङि गुणः । ७ । ४ । १६ । ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ।

२४०७ । न दृशः । ३ । १ । ४७ । दृशश्च्लेः क्सो न । अद्राक्षीत् । 'दंश ९८९ दशने' । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एव निपातनादित्येके । तस्याप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । 'दंशसञ्ज–' (सू २३९६) इति नलोपः । दशति । ददंशिथ–ददंष्ठ । दंष्टा । दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् । 'कृष ९९० विलेखने' । विलेखनमाकर्षणम् । क्रष्टा–कर्ष्टा । क्रक्ष्यति–कर्क्ष्यति । 'स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः' (वा १८२६) । आक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अकृक्षन् । 'दह ९९१ भस्मीकरणे' । देहिथ–ददग्ध । दग्धा । धक्ष्यति । अधाक्षीत् । अदाग्धाम् । अधाक्षुः । 'मिह ९९२ सेचने' । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति । अमिक्षत् । 'कित ९९३ निवासे रोगापनयने च' । चिकित्सति । संशये प्रायेण विपूर्वः । 'विचिकित्सा तु संशयः' इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य 'चिकित्सते' इत्यादि कश्चिदुदाजहार । निवासे तु केतयति ।

'दान ९९४ खण्डने' । 'शान ९९५ तेजने' । इतो वहत्यन्ताः स्वरितेतः । दीदांसति–दीदांसते । शीशांसति–शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति । शानयति । 'डुपचष् ९९६ पाके' । पचति–पचते । पेचिथ–पपक्थ । पेचे । पक्ता । पक्षीष्ट । 'षच ९९७ समवाये' । सचति । सचते । 'भज ९९८ सेवायाम्' । बभाज । भेजतुः । भेजुः । भेजिथ–बभक्थ । भक्ता । भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त । 'रञ्ज ९९९ रागे' । नलोपः । रजति–रजते । अराङ्क्षीत्–अरङ्क्त । 'शप १००० आक्रोशे' । आक्रोशो विरुद्धानुध्यानम् । शशाप–शेपे । अशाप्सीत्–अशप्त । 'त्विष १००१ दीप्तौ' । त्वेषति–त्वेषते । तित्विषे । त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत । अत्विक्षाताम् । 'यज १००२ देवपूजासंगतिकरणदानेषु' । यजति–यजते ।

२४०८ । लिट्यभ्यासस्योभयेषाम् । ६ । १ । १७ । वच्यादीनां गृह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ।

२४०९ । वचिस्वपियजादीनां किति । ६ । १ । १५ । वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात्किति । पुनः प्रसङ्गविज्ञानाद्द्वित्वम् । ईजतुः । ईजुः । इयजिथ–इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट । 'डुवप् १००३ बीजसंताने' । बीजसंतानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप–ऊपे । वप्ता । उप्यात् । वप्सीष्ट । मण्यवाप्सीत्–अवप्त । 'वह १००४ प्रापणे' । उवाह । उवहिथ । 'सहि-

वहोरोदवर्णस्य' (सू२३९७) । उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढ्वम् । 'वस १००५ निवासे' परस्मैपदी । वसति । उवास ।

२४१० । शासिवसिघसीनां च । ८ । ३ । ६० । इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ-उवस्थ । वस्ता । 'सः स्यार्धधातुके' (सू २३४२) वत्स्यति । उष्यात् । अवात्सीत् अवात्ताम् । 'वेञ् १००६ तन्तुसंताने' । वयति-वयते ।

२४११ । वेञो वयिः । २ । ४ । ४१ । वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ।

२४१२ । ग्रहिज्यावयिव्याधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च । ६ । १ । १६ । एषां किति ङिति च संप्रसारणं स्यात् । यकारस्य प्राप्ते ।

२४१३ । लिटि वयो यः । ६ । १ । ३८ । वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ।

२४१४ । वश्चास्यान्यतरस्यां किति । ६ । १ । ३९ । वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्त्वात्तङ् । ऊये । ऊवे । वयादेशाभावे ।

२४१५ । वेञः । ६ । १ । ४० । वेञो न संप्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । ववाथ-ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् । 'व्येञ् १००७ संवरणे' । व्ययति ।

२४१६ । न व्यो लिटि । ६ । १ । ४६ । व्येञ आत्त्वं न स्याल्लिटि । वृद्धिः । परत्वाद्धलादिःशेषं बाधित्वा यस्य सम्प्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । 'इडत्यर्ति-'(सू२३८४) इति नित्यमिट् । विव्ययिथ । विव्याय-विव्यय । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त । 'ह्वेञ् १००८ स्पर्धायां शब्दे च' ।

२४१७ । अभ्यस्तस्य च । ६ । १ । ३३ । अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ-जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ।

२४१८ । लिपिसिचिह्वश्च । ३ । १ । ५३ । एभ्यश्च्लेरङ् स्यात् ।

२४१९ । आत्मनेपदेष्वन्यतरस्याम् । ३ । १ । ५४ । 'आतो लोपः' (सू २३७०) । अह्वत् । अह्वताम् । अह्वन् । अह्वत । अह्वास्त ।

अथ द्वौ परस्मैपदिनौ । 'वद १००९ व्यक्तायां वाचि' । अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । 'वदव्रज-' (सू २२६७) इति वृद्धिः । अवादीत् । 'टुओश्वि १०१० गतिवृद्ध्योः' । श्वयति ।

२४२० । विभाषा श्वेः । ६ । १ । ३० । श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः । 'श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः' (वा ३४६२) । तेन 'लिट्यभ्यासस्य-' (सू २४०८) इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । 'जृस्तम्भु-' (सू २२९१) इत्यङ् वा ।

२४२१ । श्वयतेरः । ७ । ४ । १८ । श्वयतेरिकारस्याकारः स्यादङि । पररूपम् ।

अश्वत् । अश्वताम् । अश्वन् । 'विभाषा धेट्श्व्योः' (सू २३७५) इति चङ् । इयङ् । अशिश्वियत् । 'ह्यन्त–' (सू २२९९) इति न वृद्धिः । अश्वयीत् । वृत् । यजादयो वृत्ताः । भ्वादिस्त्वाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ।

इति तिङन्तभ्वादिप्रकरणम् ।

अथ तिङन्तादादिप्रकरणम् ।

२४२२ । ऋतेरीयङ् । ३ । १ । २९ । ऋतिः सौत्रस्तस्मादीयङ् स्यात्स्वार्थे । 'जुगुप्सायामयं धातुः' इति बहवः । 'कृपायां च' इत्येके । 'सनाद्यन्ताः–' (सू २३०४) इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षायां तु 'आयादय आर्धधातुके वा' (सू २३०५) ईतीयङभावे 'शेषात्कर्तरि–' (सू २१५९) इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् । 'अद १०११ भक्षणे' । द्वौ परस्मैपदिनौ ।

२४२३ । अदिप्रभृतिभ्यः शपः । २ । ४ । ७२ । लुक्स्यात् । अत्ति । अत्तः । अदन्ति ।

२४२४ । लिट्यन्यतरस्याम् । २ । ४ । ४० । अदो घस्लृ वा स्याल्लिटि । जघास । 'गमहन–' (सू २३६३) इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्घस्य चर्त्वम् । 'शासिवसि–' (सू२४१०) इति षत्वम् । जक्षतुः । जक्षुः । घसेस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । 'इडत्त्यर्ति–' (सू २३८४) इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ।

२४२५ । हुझल्भ्यो हेर्धिः । ६ । ४ । १०१ । होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धि । अत्तात् । अदानि ।

२४२६ । अदः सर्वेषाम् । ७ । ३ । १०० । अदः परस्यापृक्तसार्वधातुकस्याडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ।

२४२७ । लुङ्सनोर्घस्लृ । २ । ४ । ३७ । अदो घस्लृ स्याल्लुङि सनि च । लृदित्वादङ् । अघसत् । 'हन १०१२ हिंसागत्योः' । प्रणिहन्ति ।

२४२८ । अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति । ६ । ४ । ३७ । 'अनुनासिक–' इति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनुतनोत्यादयः । हतः । घ्नन्ति ।

२४२९ । वमोर्वा । ८ । ४ । २३ । उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि–प्रहन्मि । प्रहण्वः–प्रहन्वः । 'हो हन्तेः–' (सू ३५८) इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ।

२४३० । अभ्यासाच्च । ७ । ३ । ५५ । अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ–जघन्थ । हन्ता । 'ऋद्धनोः–' (सू २३६६) इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ।

२४३१ । हन्तेर्जः । ६ । ४ । ३६ । हौ परे । आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ।

२४३२। आर्धधातुके। २। ४। ३५। इत्यधिकृत्य।

२४३३। हनो वध लिङि। २। ४। ४२।

२४३४। लुङि च। २। ४। ४३। वधादेशोऽदन्तः। 'आर्धधातुके' (सू २३३१) इति विषयसप्तमी। तेनार्धधातुकोपदेशेऽकारान्तत्वात् 'अतो लोपः' (सू २३०८)। वध्यात् वध्यास्ताम्। 'आर्धधातुके' किम्। विध्यादौ हन्यात्। 'हन्तेः–' (सू ३५९) इति णत्वम् प्रहण्यात्। अवधीत्।

अथ चत्वारः स्वरितेतः। 'द्विष १०१३ अप्रीतौ'। द्वेष्टि–द्विष्टे। द्वेष्टा। द्वेक्ष्यति–द्वेक्ष्यते। द्वेष्टु–द्विष्टात्। द्विड्ढि। द्वेषाणि। द्वेषै। द्वेषावहै। अद्वेट्।

२४३५। द्विषश्च। ३। ४। ११२। लङो झेर्जुस् वा स्यात्। अद्विषुः। अद्विषन् अद्वेषम्। द्विष्यात। द्विक्षीष्ट। अद्विक्षत्। 'दुह १०१४ प्रपूरणे'। दोग्धि। दुग्धः। धोक्षि। दुग्धे धुक्षे। धुग्ध्वे। दोग्धु। दुग्धि। दोहानि। धुक्ष्व। धुग्ध्वम्। दोहै। अधोक्। अदोहम् अधुग्ध्वम्। अधुक्षत्–अधुक्षत। 'लुग्वा दुह–' (सू २३६५) इति लुक्पक्षे तथास्थाम्भ्यां लङ्वदपि। 'दिह १०१५ उपचये'। उपचयो वृद्धिः। प्रणिदेग्धि। 'लिह १०१६ आस्वादने' लेढि। लीढः। लिहन्ति। लेक्षि–लीढे। लिक्षे। लीढ्वे। लेढु। लीढाम्। लेहानि। अलेट् अलिक्षत। अलिक्षताम्। अलीढ। अलिक्षावहि। 'चक्षिङ् १०१७ व्यक्तायां वाचि'। अयं दर्शनेऽपि। इकारोऽनुदात्तो युजर्थः। 'विचक्षणः प्रथयन्'। नुम्तु न। 'अन्तेदितः' इति व्याख्या नात्। ङकारस्तु 'अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम्' (प ९७) इति ज्ञापनार्थः। तेन 'स्फायन्निर्मोकसंधि–' इत्यादि सिध्यति। चष्टे। चक्षाते। 'आर्धधातुके' (सू २३३२) इत्यधिकृत्य।

२४३६। चक्षिङः ख्याञ्। २। ४। ५४।

२४३७। वा लिटि। २। ४। ५५। अत्र भाष्ये क्शादिरयमादेशः। असिद्धः 'शस्य यो वा' (वा १५८६) इति स्थितम्। ञित्त्वात्पदद्वयम्। चख्यौ–चख्ये–चक्शौ चक्शे। 'चयो द्वितीयाः–' (वा ५०२३) इति तु न चर्त्वस्यासिद्धत्वात्। चचक्षे। ख्याता क्शाता। ख्यास्यति–ख्यास्यते। क्शास्यति–क्शास्यते। अचष्ट। चक्षीत। ख्यायात् क्शायात्–क्शेयात्।

२४३८। अस्यतिवक्तिख्यातिभ्योऽङ्। ३। १। ५२। एभ्यश्च्लेरङ्। अख्यत् अख्यत–अक्शासीत्–अक्शास्त। 'वर्जने क्शाञ्नेष्टः' (वा १५९२)। समचाक्षिष्ट।

अथ पृच्यन्ता अनुदात्तेतः। 'ईर १०१८ गतौ कम्पने च'। ईर्ते। ईरां चक्रे। ईरिता ईरिष्यते। ईर्ताम्। ईर्ष्व। ईर्ध्वम्। ऐरिष्ट। 'ईड १०१९ स्तुतौ'। ईट्टे।

२४३९। ईशः से। ७। २। ७७।

२४४०। ईडजनोर्ध्वे च। ७। २। ७८। ईशीड्जनां 'से–' 'ध्वे–' शब्दयोः सार्वधातुकयोरिट् स्यात्। योगविभागो वैचित्र्यार्थः। ईडिषे। ईडिध्वे। 'एकदेशविकृतस्यानन्यत्वात्' (प ३८)। ईडिष्व। ईडिध्वम्। 'विकृतिग्रहणेन प्रकृतेरग्रहणात्'। ऐड्ढ्वम्। 'ईश १०२० ऐश्वर्ये'। ईष्टे। ईशिषे। ईशिध्वे। 'आस १०२१ उपवेशने'। आस्ते। 'दयायास' (सू २३२४)। आसांचक्रे। आस्स्व। आध्वम्। आसिष्ट। 'आङ्शासु १०२२ इच्छायाम्'

आशास्ते । आशासाते । आङ्पूर्वत्वं प्रायिकम् । तेन 'नमोवाकं प्रशास्महे' इति सिद्धम् । 'वस १०२३ आच्छादने' । वस्ते । वस्से । वध्वे । ववसे । वसिता । 'कसि १०२४ गतिशासनयोः' । कंस्ते । कंसाते । कंसते । 'अयमनिदित् इत्येके' । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । 'णिसि १०२५ चुम्बने' । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । 'णिजि १०२६ शुद्धौ' । निङ्क्ते । निङ्क्ष्वे । निञ्जिता । 'शिजि १०२७ अव्यक्ते शब्दे' । शिङ्क्ते । 'पिजि १०२८ वर्णे' । 'संपर्चन इत्येके' । उभयत्रेत्यन्ये । 'अवयवे इत्यपरे । 'अव्यक्ते शब्दे' इतीतरे । पिङ्क्ते । 'पृजि' इत्येके । पृङ्क्ते । 'वृजी १०२९ वर्जने' । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । 'इदित्' । इत्यन्ये । वृङ्क्ते । 'पृची १०३० संपर्चने' । पृक्ते ।

'षूङ् १०३१ प्राणिगर्भविमोचने' । सूते । सुषुवे । सोता–सविता । 'भूसुवोः–' (सू २२२४) इति गुणनिषेधः । सुवै । सविषीष्ट । असविष्ट–असोष्ट । 'शीङ् १०३२ स्वप्ने' ।

२४४१ । शीङः सार्वधातुके गुणः ७ । ४ । २१ । 'क्ङिति च' (सू २२१७) इत्यस्यापवादः । शेते । शयाते ।

२४४२ । शीङो रुट् । ७ । १ । ६ । शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ।

अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । 'यु १०३३ मिश्रणेऽमिश्रणे च' ।

२४४३ । उतो वृद्धिर्लुकि हलि । ७ । ३ । ८९ । लुग्विषय उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह 'उतो वृद्धिः–' न । भाष्ये 'पिच्च ङिन्न' 'ङिच्च पिन्न' इति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् । 'रु १०३४ शब्दे' ।

२४४४ । तुरुस्तुशम्यमः सार्वधातुके । ७ । ३ । ९५ । एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । 'नाभ्यस्तस्य–' (सू २५०३) इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति–रौति । रुवीतः–रुतः । 'हलादेः' किम् । रुवन्ति । 'तिङः' किम् । शाम्यति । 'सार्वधातुके' किम् । आशिषि रूयात् । विध्यादौ तु रुयात्–रुवीयात् । अरावीत् । अराविष्यत् । 'तु' इति सौत्रो धातुर्गतिवृद्धिहिंसासु । 'अयं च लुग्विकरणः' इति स्मरन्ति । तवीति–तौति । तुवीतः–तुतः । तोता । तोष्यति । 'णु १०३५ स्तुतौ' । नौति । नविता । 'टुक्षु १०३६ शब्दे' । क्षौति । क्षविता । 'क्ष्णु १०३७ तेजने' । क्ष्णौति । क्ष्णविता । 'ष्णु १०३८ प्रस्रवणे' । स्नौति । सुष्णाव । स्नविता । स्नूयात् । 'ऊर्णुञ् १०३९ आच्छादने' ।

२४४५ । ऊर्णोतेर्विभाषा । ७ । ३ । ९० । वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति–ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । ऊर्णुवाते । ऊर्णुवते । 'ऊर्णोतेराम्नेति वाच्यम्' (वा १८०२)

२४४६ । न न्द्राः संयोगादयः । ६ । १ । ३ । अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७) इति त्वनित्यम् । 'उभौ साभ्यासस्य' (सू २६०६) इति लिङ्गात् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ।

२४४७ । विभाषोर्णोः । १ । २ । ३ । इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ-ऊर्णुनुविथ । ऊर्णुविता-ऊर्णविता । ऊर्णौतु-ऊर्णोतु । ऊर्णवानि-ऊर्णवै ।

२४४८ । गुणोऽपृक्ते । ७ । ३ । ९१ । ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । 'ङिच्च पित्' इति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट-ऊर्णुविषीष्ट । और्णुवीत्-और्णुविष्टाम् ।

२४४९ । ऊर्णोतेर्विभाषा । ७ । २ । ६ । इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्णाविष्टाम् । और्णाविषुः । और्णवीत् । 'द्यु १०४० अभिगमने' । द्यौति । द्योता । 'षु १०४१ प्रसवैश्वर्ययोः' । प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् । 'कु १०४२ शब्दे' । कोता । 'ष्टुञ् १०४३ स्तुतौ' । स्तौति-स्तवीति । स्तुतः-स्तुवीतः । स्तुते-स्तुवीते । 'स्तुसुधूञ्भ्यः-' (सू २३८५) इतीट् । अस्तावीत् । 'प्राक्सितात्-' (सू २२७६) इति षत्वम् । अभ्यष्टौत् । 'सिवादीनां वा-' (सू २३९९) । पर्यष्टौत्-पर्यस्तौत् । 'ब्रूञ् १०४४ व्यक्तायां वाचि' ।

२४५० । ब्रुवः पञ्चानामादित आहो ब्रुवः । ३ । ४ । ८४ । ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । अकार उच्चारणार्थः । आह । आहतुः । आहुः ।

२४५१ । आहस्थः । ८ । २ । ३५ । झलि परे । चर्त्वम् । आत्थ । आहथुः ।

२४५२ । ब्रुव ईट् । ७ । ३ । ९३ । ब्रुवः परस्य हलादेः पित ईट् स्यात् । 'आह' इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ।

२४५३ । ब्रुवो वचिः । २ । ४ । ५३ । उवाच । ऊचतुः । ऊचुः । उवचिथ-उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूयात् । 'ङिच्च पिन्न' इत्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । 'अस्यतिवक्ति-' (सू २४३८) इत्यङ् ।

२४५४ । वच उम् । ७ । ४ । २० । अङि परे । अवोचत्-अवोचत ।

अथ शास्यन्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी । 'इण् १०४५ गतौ' । एति । इतः ।

२४५५ । इणो यण् । ६ । ४ । ८१ । अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ।

२४५६ । दीर्घ इणः किति । ७ । ४ । ६९ । इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ-इयेथ । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ।

२४५७ । एतेर्लिङि । ७ । ४ । २४ । उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । 'उभयत आश्रये नान्तादिवत्-' । अभीयात् । 'अणः' किम् । समेयात् । 'समीयात्' इति प्रयोगस्तु भौवादिकस्य ।

२४५८ । इणो गा लुङि । २ । ४ । ४५ । 'गातिस्था-' (२२२३) इति सिचो लुक् । अगात् । अगाताम् । अगुः । 'इङ् १०४६ अध्ययने' । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ।

२४५९ । गाङ् लिटि । २ । ४ । ४९ । इङो गाङ् स्याल्लिटि लावस्थायां विवक्षिते । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशौ ।

कृतयोरुपसर्गस्य यण् । 'पूर्वं धातुरुपसर्गेण–' इति दर्शनेऽन्तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । 'णेरध्ययने वृत्तम्' (सू २०६६) इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ।

२४६० । विभाषा लुङ्लृङोः । २ । ४ । ५० । इङो गाङ् वा स्यात् ।

२४६१ । गाङ्कुटादिभ्योऽञ्णिन्ङित् । १ । २ । १ । गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ।

२४६२ । घुमास्थागापाजहातिसां हलि । ६ । ४ । ६६ । एषामात ईत्स्यात् हलादौ क्ङित्यार्धधातुके । अध्यगीष्ट–अध्यैष्ट । अध्यगीष्यत–अध्यैष्यत । 'इक् १०४७ स्मरणे' । अयमप्यधिपूर्वः । 'अधीगर्थदयेशाम्–' (सू ६१२) इति लिङ्गात् । अन्यथा हि 'इगर्थ–' इत्येव ब्रूयात् । 'इण्वदिक इति वक्तव्यम्' (वा १५७७) । अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथा च भट्टिः–'ससीतयो राघवयोरधीयन्' इति । 'वा १०४८ गतिव्याप्तिप्रजनकान्त्यसनखादनेषु' । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्यनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्रेकारोऽपि धात्वन्तरं प्रश्लिष्यते । एति । ईतः । इयन्ति । ईयात् । ऐषीत् । 'या १०४९ प्रापणे' । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ।

२४६३ । लङः शाकटायनस्यैव । ३ । ४ । १११ । आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः–अयान् । यायात् । यायाताम् । यायास्ताम् । 'वा १०५० गतिगन्धनयोः' । गन्धनं सूचनम् । 'भा १०५१ दीप्तौ' । 'ष्णा १०५२ शौचे' । 'श्रा १०५३ पाके' । 'द्रा १०५४ कुत्सायां गतौ' । 'प्सा १०५५ भक्षणे' । 'पा १०५६ रक्षणे' । पायास्ताम् । अपासीत् । 'रा १०५७ दाने' । 'ला १०५८ आदाने' । 'द्वावपि दाने' इति चन्द्रः । 'दाप् १०५९ लवने' । प्रणिदाति–प्रनिदाति । दायास्ताम् । अदासीत् । 'ख्या १०६० प्रकथने' । अयं सार्वधातुकमात्रविषयः । 'सस्थानत्वं नमः ख्याञे' (वा १५९१) इति वार्तिकम् । तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः । स नेति ख्शाञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । 'संपूर्वस्य ख्यातेः प्रयोगो न' इति न्यासकारः । 'प्रा १०६१ पूरणे' । 'मा १०६२ माने' । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विषः' इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । 'उदरं परिमाति मुष्टिना' । 'नेर्गद–' (सू २२८५) इत्यत्र नास्य ग्रहणम् । प्रणिमाति–प्रनिमाति । 'वच १०६३ परिभाषणे' । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । 'बहुवचनपरः' इत्यन्ये । 'झिपरः' इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् । 'विद १०६४ ज्ञाने' ।

२४६४ । विदो लटो वा । ३ । ४ । ८३ । वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्त इत्यादि । विवेद । विविदतुः । 'उषविद–' (सू २३४१) इत्याम्पक्षे 'विद' इत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ।

२४६५ । विदांकुर्वन्त्वित्यन्यतरस्याम् । ३ । १ । ४१ । वेत्तेर्लोटचाम्गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इति शब्दात ।

२४६६ । तनादिकृञ्भ्य उः । ३ । १ । ७९ । तनादेः कृञश्च 'उ'प्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेव सिद्धे कृञ्ग्रहणं 'गणकार्यस्यानित्यत्वे' लिङ्गम् । तेन 'न विश्वसेदविश्वस्तम्' इत्यादि सिद्धम् । विदां करोतु ।

२४६७ । अत उत्सार्वधातुके । ६ । ४ । ११० । उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्ङिति । उदिति तपरसामर्थ्यान्न गुणः । विदां कुरुतात् । विदां कुरुताम् । 'उतश्च-'(सू २३३४) इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादुत्त्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अविताम् । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अविदुः ।

२४६८ । दश्च । ८ । २ । ७५ । धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा । अवेः-अवेत् । 'अस् १०६५ भुवि' । अस्ति ।

२४६९ । श्नसोरल्लोपः । ६ । ४ । १११ । श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः । सन्ति । 'तासस्त्योः-' (सू २१९१) इति सलोपः । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । 'आर्धधातुके' (सू २४३२) इत्यधिकृत्य ।

२४७० । अस्तेर्भूः । २ । ४ । ५२ । बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ।

२४७१ । घ्वसोरेद्धावभ्यासलोपश्च । ६ । ४ । ११९ । घोरस्तेश्चैत्त्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्त्वस्यासिद्धत्वाद्धेर्धिः । 'श्नसोः-' (सू २४६९) इत्यल्लोपः । एधि । तातङ्पक्षे एत्त्वं न । परेण तातङा बाधात् । 'सकृद्गतौ-' (प ४१) इति न्यायात् । स्तात् । स्तम् । स्त । असानि । असाव । असाम । 'अस्तिसिचः-' (सू २२२५) इतीट् । आसीत् । 'श्नसोः-' (सू २४६९) इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ।

२४७२ । उपसर्गप्रादुर्भ्यामस्तिर्यच्परः । ८ । ३ । ८७ । उपसर्गेणः प्रादुसश्च परस्यास्तेः सस्य षः स्याद्यकारेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुःषन्ति । 'यच्परः' किम् । अभिस्तः । 'मृजू १०६६ शुद्धौ' ।

२४७३ । मृजेर्वृद्धिः । ७ । २ । ११४ । मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे । 'क्ङिति अजादौ वेष्यते-' (वा ५०५७) । 'व्रश्च-' (सू २९४) इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ-ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमार्ट् । अमार्जम् । अमार्जीत्-अमार्क्षीत् । 'रुदिर् १०६७ अश्रुविमोचने' ।

२४७४ । रुदादिभ्यः सार्वधातुके । ७ । २ । ७६ । 'रुद्' 'स्वप्' 'श्वस्' 'अन्' 'जक्ष्' एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ।

२४७५ । रुदश्च पञ्चभ्यः । ७ । ३ । ९८ । हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ।

२४७६ । अड्गार्ग्यगालवयोः । ७ । ३ । ९९ । अरोदीत्-अरोदत् । अरुदिताम् । अरुदन् । अरोदीः-अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्यामडीड्भ्यामन्तरङ्गत्वाद्गुणः

१अत्र 'इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते । तदिहापि साध्यं' इति 'इको गुण' इति सूत्रस्थं भाष्यं मानम् ।

रुद्यात्। अरुदत्–अरोदीत्। 'ञिष्वप् १०६८ शये'। स्वपिति। स्वपितः। सुष्वाप। सुषुपतुः। सुषुपुः। सुष्वपिथ–सुष्वप्थ।

२४७७। सुविनिर्दुर्भ्यः सुपिसूतिसमाः। ८। ३। ८८। एभ्यः सुप्यादेः सस्य षः स्यात्। 'पूर्वं धातुरुपसर्गेण युज्यते'। किति लिटि परत्वात्संप्रसारणे षत्वे च कृते द्वित्वम्। 'पूर्वत्रासिद्धीयमद्विर्वचने' (प १२७)। सुषुषुपतुः। सुषुषुपुः। अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम्। षत्वस्यासिद्धत्वात्ततः पूर्वं 'हलादिः शेषः' (सू २१७९)। नित्यत्वाच्च। ततः सुपिरूपाभावान्न षः। सुसुष्वाप। सुस्वप्ता। अस्वपीत्–अस्वपत्। स्वप्यात्। सुप्यात्। सुषुप्यात्। अस्वाप्सीत्। 'श्वस १०६९ प्राणने'। श्वसिति। श्वसिता। अश्वसीत्–अश्वसत्। श्वस्याताम्। श्वस्यास्ताम्। 'ह्म्यन्तक्षण–' (सू २२९९) इति न वृद्धिः। अश्वसीत्। 'अन १०७० च'। अनिति। आन। अनिता। आनीत्–आनत्।

२४७८। अनितेः। ८। ४। १९। उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात्। प्राणिति। 'जक्ष १०७१ भक्षहसनयोः'। जक्षिति। जक्षितः।

२४७९। अदभ्यस्तात्। ७। १। ४। झस्य अत्स्यात्। अन्तापवादः। जक्षति। 'सिजभ्यस्त–' (सू २२२६) इति झेर्जुस्। अजक्षुः। अयमन्तःस्थादिरित्युज्ज्वलदत्तो बभ्राम। रुदादयः पञ्च गताः।

'जागृ १०७२ निद्राक्षये'। जागर्ति। जागृतः। जाग्रति। 'उषविद–' (सू २३४१) इत्याम्वा। जागरांचकार–जजागार।

२४८०। जाग्रोऽविचिण्णल्ङित्सु। ७। ३। ८५। जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च। जजागरतुः। अजागः। अजागृताम्। अभ्यस्तत्वाज्जुस्।

२४८१। जुसि च। ७। ३। ८३। अजादौ जुसींगन्ताङ्गस्य गुणः स्यात्। अजागरुः। 'अजादौ' किम्। जागृयुः। आशिषि तु जागर्यात्। जागर्यास्ताम्। जागर्यासुः। लुङि अजागरीत्। 'जागृ इस्' इत्यत्र यण्प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तलक्षणा प्राप्ता, 'नेटि' (सू २२६८) इति निषिद्धा, ततः 'अतो हलादेः–' (सू २२८४) इति बाधित्वा 'अतो ल्रान्तस्य' (सू २३३०) इति प्राप्ता, 'ह्म्यन्त–' (सू२२९९) इति निषिध्यते। तदाहुः—

'गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम्।
पुनर्वृद्धिर्निषेधोऽतो यण्पूर्वाः प्राप्तयो नव॥'

इति। 'दरिद्रा १०७३ दुर्गतौ'। दरिद्राति।

२४८२। इद्दरिद्रस्य। ६। ४। ११४। दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके। दरिद्रितः।

२४८३। श्नाभ्यस्तयोरातः। ६। ४। ११२। अनयोरातो लोपः स्यात्क्ङिति सार्वधातुके। दरिद्रति। अनेकाच्त्वादाम्। दरिद्रां चकार। 'आत औ णलः' (सू२३७१) इत्यत्र 'ओ' इत्येव सिद्धे औकारविधानं दरिद्रातेरालोपे कृते श्रवणार्थम्। अत एव ज्ञापकादामेत्येके। ददरिद्रौ। ददरिद्रतुरित्यादि। यत्तु णलि ददरिद्रेति तन्निर्मूलमेव। 'दरिद्रातेरार्धधातुके

विवक्षित आलोपो वाच्यः' (वा ४१४६)। 'लुङि वा' (वा ४१४२)। '[illegible] ण्वुलि ल्युटि च न' (वा ५०९८)। दरिद्रिता। अदरिद्रात्। अदरिद्रिताम्। अदरिद्रुः। दरिद्रियात्–दरिद्यात् ['दरिद्रियात्' इति विधिलिङि, 'दरिद्यात्' इत्याशिषि।] अदरिद्रीत्। इट्सकौ। अदरिद्रासीत्। 'चकासृ १०७४ दीप्तौ'। झस्य अत्। चकासति। चकासां चकार। 'धि च' (सू २२४९) इति सलोपः। सिच एवेत्येके। चकाद्धि। 'चकाधि' इत्येव भाष्यम्।

२४८४। तिप्यनस्तेः। ८।२।७३। पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः। [ससजुषोरित्यस्यापवादः।] अचकात्–अचकाद्। अचकासुः।

२४८५। सिपि धातो रुर्वा। ८।२।७४। पदान्तस्य धातोः सस्य रुः स्याद्वा। पक्षे [जश्त्वेन] दः। अचकाः–अचकात्। 'शासु १०७५ अनुशिष्टौ'। शास्ति।

२४८६। शास इदङ्हलोः। ६।४।३४। शास उपधाया इत्स्यादङि हलादौ क्ङिति च। 'शासिवसि–' (सू २४१०) इति षः। शिष्टः। शासति। शशास। शशासतुः। शास्तु–शिष्टात्। शिष्टाम्। शासतु।

२४८७। शा हौ। ६।४।३५। शास्तेः शादेशः स्याद्धौ परे। तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः। शाधि। अशात्। अशिष्टाम्। अशासुः। अशात्–अशाः। शिष्यात्। 'सर्तिशास्ति–' (सू २३८२) इत्यङ्। अशिषत्। अशासिष्यत्।

'दीधीङ् १०७६ दीप्तिदेवनयोः'। एतदादयः पञ्च धातवश्छान्दसाः। दीधीते। 'एरनेकाचः–' (सू २७२) इति यण्। दीध्याते।

२४८८। यीवर्णयोर्दीधीवेव्योः। ७।४।५३। एतयोरन्त्यस्य लोपः स्याद्यकार इवर्णे च परे। इति लोपं बाधित्वा नित्यत्वाट्टेरेत्वम्। दीध्ये। 'दीधीवेवीटाम्' (सू २१९०) इति गुणनिषेधः। दीध्यांचक्रे। दीधिता। दीधिष्यते। 'वेवीङ् १०७७ वेतिना तुल्ये'। वेतिना त्यनेन तुल्येऽर्थे वर्तत इत्यर्थः।

अथ त्रयः परस्मैपदिनः। 'षस १०७८ सस्ति १०७९ स्वप्ने'। सस्ति। सस्तः। ससन्ति। ससास। सेसतुः। सस्तु। सधि। 'पूर्वत्रासिद्धम्' (सू १२) इति सलोपस्यासिद्धत्वात् 'अतो हेः' (सू २२०२) इति न लुक्। असत्। अस्ताम्। असः–असत्। सस्यात्। असासीत्–असीत्। सन्ति। इदित्त्वान्नुमि कृते 'संस्तः' इदि स्थिते 'स्कोः–' (सू ३८०) इति सलोपे 'झरो झरि सवर्णे' (सू ७१) इति तकारस्य वा लोपः। सन्तः। संस्तन्ति। बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य 'स्कोः–' (सू ३८०) इति लोपाभावात्। संस्ति। संस्तः। संस्तन्ति इत्येके। 'वश १०८० कान्तौ'। कान्तिरिच्छा। वष्टि। उष्टः। उशन्ति। वक्षि। उष्ठः। उवाश। ऊशतुः। वशिता। वष्टु। उष्टात्। उड्ढि। अवट्। औष्टाम्। औशन्। अवशम्। उश्यात्। उश्यास्ताम्। 'चर्करीतं च' (ग सू १९९)। यङ्लुगन्तमदादौ बोध्यम्। 'ह्नुङ् १०८२ अपनयने'। ह्नुते। जुह्नुवे। ह्नवीत। ह्नोषीष्ट। अह्नोष्ट।

इति तिङन्तादादिप्रकरणम्।

---

१ अत्र च 'न दरिद्रायके लोपो दरिद्राणेऽपि नेष्यते।
दिदरिद्रसतीत्येके दिदरिद्रिषतीति वा॥' इति भाष्यं मानम्।

अथ तिङन्तजुहोत्यादिप्रकरणम् ।

'हु १०८३ दानादनयोः' । 'आदाने च' इत्येके । 'प्रीणनेऽपि' इति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः ।

२४८९ । जुहोत्यादिभ्यः श्लुः । २ । ४ । ७५ । शपः श्लुः स्यात् ।

२४९० । श्लौ । ६ । १ । १० । धातोर्द्वे स्तः । जुहोति । जुहुतः । 'अदभ्यस्तात्' (सू २४७९) इत्यत् । 'हुश्नुवोः—' (सू २३८७) इति यण् । जुह्वति ।

२४९१ । भीह्रीभृहुवां श्लुवच्च । ३ । १ । ३९ । एभ्यो लिटयाम्वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् 'जुसि च' (सू २४८१) इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । 'ञिभी १०८४ भये' । बिभेति ।

२४९२ । भियोऽन्यतरस्याम् । ६ । ४ । ११५ । इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः—बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता । 'ह्री १०८५ लज्जायाम्' । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार—जिह्राय । 'पॄ १०८६ पालनपूरणयोः' ।

२४९३ । अर्तिपिपर्त्योश्च । ७ । ४ । ७७ । अभ्यासस्येकारोऽन्तादेशः स्याच्छ्लौ ।

२४९४ । उदोष्ठ्यपूर्वस्य । ७ । १ । १०२ । अङ्गावयवौष्ठ्यपूर्वो य ॠत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्त्वम् । रपरत्वम् । 'हलि च' (सू ३५४) इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि 'ऋच्छत्यॄताम्' । (सू २३८३) इति गुणे प्राप्ते ।

२४९५ । शॄदॄप्रां ह्रस्वो वा । ७ । ४ । १२ । एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः । पपरतुः । पपरुः । परिता—परीता । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । 'ह्रस्वान्तोऽयम्' इति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि । प्रियात् । अपार्षीत् । पाणिनीयमते तु 'तं रोदसी पिपृतम्' इत्यादौ छान्दसत्वं शरणम् । 'डुभृञ् १०८७ धारणपोषणयोः' ।

२४९६ । भृञामित् । ७ । ४ । ७६ । 'भृञ्' 'माङ्' 'ओहाङ्' एषां त्रयाणामभ्यासस्य इत्स्याच्छ्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावाद्द्वित्वेत्त्वे । बिभरामास—बभार । बभर्थ । बभृव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् । अबिभरुः । बिभृयात् । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत । 'माङ् १०८८ माने शब्दे च' ।

२४९७ । ई हल्यघोः । ६ । ४ । ११३ । श्नाभ्यस्तयोरात ईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । 'श्नाभ्यस्तयोः—' (सू २४८३) इत्यालोपः । मिमाते । मिमते । मण्यमास्त । 'ओहाङ् १०८९ गतौ' । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । 'ओहाक् १०९० त्यागे' । परस्मैपदी । जहाति ।

२४९८ । जहातेश्च । ६ । ४ । ११६ । इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्ष ईत्वम् । जहितः—जहीतः । जहति ।

२४९९ । आ च हौ । ६ । ४ । ११७ । जहातेर्हौ परे आ स्याच्चादिदीतौ । जहाहि—जहिहि—जहीहि । अजहात् । अजहुः ।

२५०० । लोपो यि । ६ । ४ । ११८ । जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । 'एर्लिङि' (सू २३७४) । हेयात् । अहासीत् । 'डुदाञ् १०९१ दाने' । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । 'घ्वसोः–' (सू २४७१) इत्येत्त्वाभ्यासलोपौ । देहि । अददात् । अदत्ताम् । अददुः । दद्यात् । देयात् । अदात् । अदाताम् । अदुः । अदित । 'डुधाञ् १०९२ धारणपोषणयोः' । 'दानेऽपि' इत्येके । प्रणिदधाति ।

२५०१ । दधस्तथोश्च । ८ । २ । ३८ । द्विरुक्तस्य झषन्तस्य धाधातोर्बशो भष् स्यात् तथयोः स्ध्वोश्च परतः । 'वचनसामर्थ्यादालोपो न स्थानिवत्' इति वामनमाधवौ । वस्तुतस्तु 'पूर्वत्रासिद्धे न स्थानिवत्' । धत्तः । दधाति । धत्थः । धत्थ । दध्वः । दध्मः । धत्ते । धत्से । धद्ध्वे । धेहि । अधित ।

अथ त्रयः स्वरितेतः । 'णिजिर् १०९३ शौचपोषणयोः' ।

२५०२ । निजां त्रयाणां गुणः श्लौ । ७ । ४ । ७५ । निज्विज्विषामभ्यासस्य गुणः स्याच्छ्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्धि ।

२५०३ । नाभ्यस्तस्याचि पिति सार्वधातुके । ७ । ३ । ८७ । लघूपधगुणो न स्यात् । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त । 'विजिर् १०९४ पृथग्भावे' । वेवेक्ति-वेविक्ते । विवेजिथ । अत्र 'विज इट्' (सू २५३६) इति ङित्त्वं न । 'ओविजी' इत्यस्यैव तत्र ग्रहणात् । 'णिजिविजी' रुधादावपि । 'विष्लृ १०९५ व्याप्तौ' । वेवेष्टि-वेविष्टे । लृदित्त्वादङ् । अविषत् । ताङि क्सः । अजादौ 'क्सस्याचि' (सू २३३७) इत्यल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ।

अथ आगणान्तात्परस्मैपदिनश्छान्दसाश्च । 'घृ १०९६ क्षरणदीप्त्योः' । 'जिघर्म्यग्निं हविषा घृतेन' । 'भृञामित्' (सू २४९६) । 'बहुलं छन्दसि' (सू ३५९८) इतीत्त्वम् । 'हृ १०९७ प्रसह्यकरणे' । 'अयं स्रुवोऽभिजिहर्ति होमान्' । 'ऋ १०९८ सृ १०९९ गतौ' । 'बहुलं छन्दसि' (सू ३५९८) इत्येव सिद्धे 'अर्तिपिपर्त्योश्च' (सू २४९३) इतीत्त्वविधानादयं भाषायामपि । 'अभ्यासस्यासवर्णे' (सू २२९०) इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः । 'इड-त्त्यर्ति–' (सू २३८४) इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृतात् । अर्यात् । आरत् । ससर्ति । 'भस ११०० भर्त्सनदीप्त्योः' । बभस्ति । 'घसिभसोर्हलि–' (सू ३५५०) इत्युपधालोपः । 'झलो झलि' (सू २२८१) इति सलोपः । बब्धः । बप्सति । 'कि ११०१ ज्ञाने' । चिकेति । 'तुर ११०२ त्वरणे' । तुतोर्ति । तुतूर्तः । तुतुरति । 'धिष ११०३ शब्दे' । दिधेष्टि । दिधिष्टः । 'धन ११०४ धान्ये' । दधन्ति । दधन्तः । दधनति । 'जन ११०५ जनने' । जजन्ति ।

२५०४ । जनसनखनां सञ्झलोः । ६ । ४ । ४२ । एषामाकारोऽन्तादेशः स्यात् सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात्-जजायात् । जन्यात्-जायात् । 'गा ११०६ स्तुतौ' । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ।

इति तिङन्तजुहोत्यादिप्रकरणम् ।

अथ तिङन्तदिवादिप्रकरणम् ।

'दिवु ११०७ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु' । वृषन्ताः परस्मैपदिनः ।

२५०५ । दिवादिभ्यः श्यन् । ३ । १ । ६९ । शपोऽपवादः । 'हलि च' (सू ३५४) इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् । 'षिवु ११०८ तन्तुसंताने' । परिषीव्यति । परिषिषेव । न्यषेवीत्–न्यसेवीत् । 'स्रिवु ११०९ गतिशोषणयोः' । 'ष्ठिवु १११० निरसने' । केचिदिहेमं न पठन्ति । 'ष्णुसु ११११ अदने' । 'आदाने' इत्येके । 'अदर्शने' इत्यपरे । सुष्णोस । 'ष्णसु १११२ निरसने' । स्नस्यति । सस्नास । 'क्नसु १११३ ह्वरणदीप्त्योः' । ह्वरणं कौटिल्यम् । चक्नास । 'व्युष १११४ दाहे' । वुव्योष । 'प्लुष १११५ च' । 'नृती १११६ गात्रविक्षेपे' । नृत्यति । ननर्त ।

२५०६ । सेऽसिचि कृतचृतच्छृदतृदनृतः । ७ । २ । ५७ । एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्य इड्वा स्यात् । नर्तिष्यति–नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् । 'त्रसी १११७ उद्वेगे' । 'वा भ्राश–' (सू २३२१) इति श्यन्वा । त्रस्यति–त्रसति । त्रेसतुः–तत्रसतुः । 'कुथ १११८ पूतीभावे' । पूतीभावो दौर्गन्ध्यम् । 'पुथ १११९ हिंसायाम्' । 'गुध ११२० परिवेष्टने' । 'क्षिप ११२१ प्रेरणे' । क्षिप्यति । क्षेप्ता । 'पुष्प ११२२ विकसने' । पुष्प्यति । पुपुष्प । 'तिम ११२३ ष्टिम ११२४ ष्टीम ११२५ आर्द्रीभावे' । तिम्यति–स्तिम्यति–स्तीम्यति । 'व्रीड ११२६ चोदने लज्जायां च' । व्रीड्यति । 'इष ११२७ गतौ' । इष्यति । 'षह ११२८ षुह ११२९ चक्यर्थे' । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति । 'जॄष् ११३० झॄष् ११३१ वयोहानौ' । जीर्यति । जजरतुः–जेरतुः । जरिता–जरीता । जीर्येत् । जीर्यात् । 'जॄस्तम्भु–' (सू २२९१) इत्यङ्वा । 'ऋदृशोऽङि गुणः' (सू २४०६) । अजरत्–अजारीत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् । 'षूङ् ११३२ प्राणिप्रसवे' । सूयते । सुषुवे । 'स्वरतिसूति–' (सू २२७९) इति विकल्पं बाधित्वा 'श्र्युकः किति' (सू २३८१) इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता–सविता । 'दूङ् ११३३ परितापे' । दूयते । 'दीङ् ११३४ क्षये' । दीयते ।

२५०७ । दीङो युडचि क्ङिति । ६ । ४ । ६३ । दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् । 'वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ' (वा ४०६२) । दिदीये ।

२५०८ । मीनातिमिनोतिदीङां ल्यपि च । ६ । १ । ५० । एषामात्त्वं स्याल्ल्यपि । चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः । 'डीङ् ११३५ विहायसा गतौ' । डीयते । 'धीङ् ११३६ आधारे' । धीयते । दिध्ये । धेता । 'मीङ् ११३७ हिंसायाम्' । हिंसात्र प्राणवियोगः । मीयते । 'रीङ् ११३८ श्रवणे' । रीयते । 'लीङ् ११३९ श्लेषणे' ।

२५०९ । विभाषा लीयतेः । ६ । १ । ५१ । लीयतेरिति यका निर्देशो न तु श्यना । लीलीङोरात्त्वं वा स्यादेज्विषये ल्यपि च । लेता–लाता । लेष्यते । लास्यते । 'एज्विषये' किम् । लीयते । लिल्ये । 'व्रीङ् ११४० वृणोत्यर्थे' । व्रीयते । विव्रिये । '[?] स्वादय ओदितः' (ग सू १९६) । तत्फलं तु निष्ठानत्वम् । 'पीङ् ११४१ पाने' । पीयते । 'माङ् ११४२ माने' । मायते । ममे । 'ईङ् ११४३ गतौ' । ईयते । अयां चक्रे । 'प्रीङ् ११४४ प्रीतौ' । सकर्मकः । प्रीयते । पिप्रिये ।

अथ परस्मैपदिनश्चत्वारः। 'शो ११४५ तनूकरणे'।

२५१० । ओतः श्यनि । ७ । ३ । ७१ । लोपः स्याच्छ्यनि । श्यति । श्यतः । श्यन्ति। शशौ । शशतुः । शाता । शास्यति । 'विभाषा घ्राधेट्–' (सू २३७६) इति सिचो वा लुक्। लुगभावे 'यमरम–' (सू २३७७) इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत्। अशासिष्टाम् । 'छो ११४६ छेदने' । छ्यति । 'षो ११४७ अन्तकर्मणि' । स्यति । ससौ। अभिष्यति । अभ्यष्यत् । अभिससौ । 'दो ११४८ अवखण्डने' । द्यति । ददौ । प्रणिदाता। देयात् । अदात् ।

अथात्मनेपदिनः पञ्चदश । 'जनी ११४९ प्रादुर्भावे' ।

२५११ । ज्ञाजनोर्जा । ७ । ३ । ७९ । अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे। जज्ञाते । जज्ञिरे । जनिता । जनिष्यते । 'दीपजन–' (सू २३२८) इति वा चिण् ।

२५१२ । जनिवध्योश्च । ७ । ३ । ३५ । अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि–अजनिष्ट । 'दीपी ११५० दीप्तौ' । दीप्यते । दिदीपे । अदीपि–अदीपिष्ट । 'पूरी ११५१ आप्यायने' । पूर्यते । अपूरि–अपूरिष्ट । 'तूरी ११५२ गतित्वरणहिंसनयोः' । तूर्यते । तुतूरे। 'धूरी ११५३ गूरी ११५४ हिंसागत्योः' । धूर्यते । दुधूरे । गूर्यते । जुगूरे । 'घूरी ११५५ जूरी ११५६ हिंसावयोहान्योः' । 'शूरी ११५७ हिंसास्तम्भनयोः' । 'चूरी ११५८ दाहे' । 'तप ११५९ ऐश्वर्ये वा' । अयं धातुरैश्वर्ये वा तङ्श्यनौ लभते । अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधातोरादवयवमिच्छन्ति । तप्यते । तप्ता । तप्स्यते । 'पत' इति न्यत्यासेन पाठान्तरम् । 'श्रुतग्रामानियुतः पत्यमानः' । 'वृतु ११६० वरणे' । वृत्यते । पक्षान्तरे । वावृत्यते । 'ततो वावृत्यमाना सा रामशालां न्यविक्षत' इति भट्टिः । 'क्लिश ११६१ उपतापे' । क्लिश्यते। क्लेशिता । 'काशृ ११६२ दीप्तौ' । काश्यते । 'वाशृ ११६३ शब्दे' । वाश्यते । ववाशे ।

अथ पञ्च स्वरितेतः । 'मृष ११६४ तितिक्षायाम्' । मृष्यति–मृष्यते । ममर्ष–ममृषे। 'शुचिर् ११६५ पूतीभावे' । पूतीभावः क्लेदः । शुच्यति–शुच्यते । शुशोच–शुशुचे । अशुचत्–अशोचीत्–अशोचिष्ट । 'णह ११६६ बन्धने' । नह्यति–नह्यते । ननाह । ननद्ध–नेहिथ। नेहे । नद्धा । नत्स्यति । अनात्सीत् । 'रञ्ज ११६७ रागे' । रज्यति–रज्यते । 'शप ११६८ आक्रोशे' । शप्यति । शप्यते ।

अथैकादशानुदात्तेतः । 'पद ११७० गतौ' । पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट।

२५१३ । चिण् ते पदः । ३ । १ । ६० । पदश्च्लेश्चिण्स्यात्तशब्दे परे । प्रण्यपादि । अपत्साताम् । अपत्सत । 'खिद ११७१ दैन्ये' । खिद्यते । चिखिदे । खेत्ता । अखित्त । 'विद ११७२ सत्तायाम्' । विद्यते । वेत्ता । 'बुध ११७३ अवगमने' । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते। भुत्सीष्ट । अबोधि–अबुद्ध । अभुत्साताम् । 'युध ११७४ संप्रहारे' । युध्यते । युयुधे । योद्धा। अयुद्ध । कथं 'युध्यति' इति युधमिच्छतीति क्यच् । 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' (प ९७) इति वा । 'अनो रुध ११७५ कामे' । अनुरुध्यते । 'अण ११७६ प्राणने'। अण्यते । आणे । अणिता । 'अन' इति दन्त्यान्तोऽयमित्येके । 'मन ११७७ ज्ञाने' । मन्यते। मेने । मन्ता । 'युज ११७८ समाधौ' । समाधिश्चित्तवृत्तिनिरोधः । अकर्मकः । युज्यते । योक्ता। 'सृज ११७९ विसर्गे' । अकर्मकः । 'संसृज्यते सरसिजैररुणांशुभिन्नैः' । ससृजिषे । स्रष्टा। स्रक्ष्यते । 'लिङ्सिचौ–' (सू २३००) इति किल्वान्न गुणो नाप्यम् । सृक्षीष्ट । असृष्ट।

असृक्षाताम्। 'लिश ११८० अल्पीभावे'। लिश्यते। लेष्टा। लेक्ष्यसे। लिक्षीष्ट। अलिक्षत। अलिक्षाताम्।

अथागणान्तात्परस्मैपदिनः। 'राधः ११८१ अकर्मकाद्वृद्धावेव'। एवकारो भिन्नक्रमः। राधोऽकर्मकादेव श्यन्। उदाहरणमाह वृद्धाविति। यन्मह्यमपराध्यति। द्रुह्यतीत्यर्थः। 'विराध्यन्तं क्षमेत कः'। द्रुह्यन्तमित्यर्थः। राध्यत्योदनः। सिध्यतीत्यर्थः। कृष्णाय राध्यति। दैवं पर्यालोचयतीत्यर्थः। दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम्। रराध। रराधतुः। रराधिथ। 'राधो हिंसायाम्' (सू. २५३२) इत्येत्त्वाभ्यासलोपाविह न। हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात्। राद्धा। रात्स्यति। अयं स्वादिश्चुरादिश्च। 'व्यध ११८२ ताडने'। 'ग्रहिज्या-' (सू. २४१२) इति संप्रसारणम्। विध्यति। विव्याध। विविधतुः। विव्यद्ध-विव्यधिथ। व्यद्धा। व्यत्स्यति। विध्येत्। विध्यात्। अव्यात्सीत्। 'पुष ११८३ पुष्टौ'। पुष्यति। पुपोष। पुपोषिथ। पोष्टा। पोक्ष्यति। 'पुषादि-' (सू. २३४३) इत्यङ्। अपुषत्। 'शुष ११८४ शोषणे'। अशुषत्। 'तुष ११८५ प्रीतौ'। 'दुष ११८६ वैकृत्ये'। 'श्लिष ११८७ आलिङ्गने'। श्लिष्यति। शिश्लेष। श्लेष्टा। श्लेक्ष्यति।

२५१४। श्लिषः—। अस्मात्परस्यानिटश्च्लेः क्सः स्यात्। पुषाद्यङोऽपवादो न तु चिणः। पुरस्तादपवादन्यायात्।

—आलिङ्गने। ३। १। ४६। श्लिषश्च्लेरालिङ्गन एव क्सो नान्यत्र। योगविभागसामर्थ्यात् 'शल इगुपधात्-' (सू. २३३६) इत्यस्याप्ययं नियमः 'अश्लिक्षत्कन्यां देवदत्तः'। 'आलिङ्गन एव' इति किम्। समश्लिषज्जतुकाष्ठम्। अङ्। प्रत्यासत्ताविह श्लिषिः। कर्मण्यनालिङ्गने सिजेव न तु क्सः। एकवचने चिण्। अश्लेषि। अश्लिक्षाताम्। अश्लिक्षन्त। अश्लिट्ठाः। अश्लिड्ढ्वम्। 'शक ११८८ विभाषितोऽमर्षणे'। विभाषित इत्युभयपदीत्यर्थः। शक्यति-शक्यते हरिं द्रष्टुं भक्तः। शशाक। शेकिथ-शशक्थ। शेके। शक्ता। शक्ष्यति-शक्ष्यते। अशकत्-अशक्त। सेट्कोऽयमित्येके। तन्मतेनानिट्कारिकासु लृदित्पाठितः। शकिता। शकिष्यति। 'ष्विदा ११८९ गात्रप्रक्षरणे'। घर्मस्रुतावित्यर्थः। अयं ञीदिति न्यासकारादयः। नेति हरदत्तादयः। स्विद्यति। सिष्वेद। सिष्वेदिथ। स्वेत्ता। अस्विदत्। 'क्रुध ११९० क्रोधे'। क्रोद्धा। क्रोत्स्यति। 'क्षुध ११९१ बुभुक्षायाम्'। क्षोद्धा। कथं क्षुधित इति। संपदादिक्विबन्तात्तारकादित्वादितजिति माधवः। वस्तुतस्तु 'वसतिक्षुधोः-' (सू. ३०४६) इतीट्। 'शुध ११९२ शौचे'। शुध्यति। शुशोध। शोद्धा। 'षिधु ११९३ संराद्धौ'। ऊदित्पाठः प्रामादिकः। सिध्यति। सेद्धा। सेत्स्यति। असिधत्। 'रध ११९४ हिंसासंराद्ध्योः'। संराद्धिर्निष्पत्तिः। रध्यति। 'रधिजभोरचि' (सू. २३०२) इति नुम्। ररन्ध। ररन्धतुः।

२५१५। रधादिभ्यश्च। ७। २। ४५। 'रध्' 'नश्' 'तृप्' 'दृप्' 'द्रुह्' 'मुह' 'ष्णुह्' 'ष्णिह्' एभ्यो वलाद्यार्धधातुकस्य वेट स्यात्। ररन्धिथ-ररद्ध। ररन्धिव-रेध्व।

२५१६। नेड्वलिटि रधेः। ७। १ ६२। लिड्वर्जे इटि रधेर्नुन्न स्यात्। रधिता-रद्धा। रधिष्यति-रत्स्यति। अङि नुम्। 'अनिदिताम्-' (सू. ४१५) इति नलोपः। अरधत्। 'णश ११९५ अदर्शने'। नश्यति। ननाश। नेशतुः। नेशिथ।

२५१७ । मस्जिनशोर्झलि । ७ । १ । ६० । नुम्स्यात् । ननंष्ठ । नेशिव-नेंष्ठ । नेशिम-नेश्म । नशिता-नंष्टा । नशिष्यति-नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ।

२५१८ । नशेः षान्तस्य । ८ । ४ । ३६ । णत्वं न स्यात् । प्रनंष्ट । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्ष्यति-नशिष्यति । 'तृप ११९६ प्रीणने' । प्रीणनं तृप्तिस्तर्पणं च । 'नाग्निस्तृप्यति काष्ठानाम्' । 'पितॄनताप्सीत्' इति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ-ततर्प्थ-तत्रप्थ । तर्पिता-तर्प्ता-त्रप्ता । 'कृशमृशस्पृश-' इति सिज्वा । अताप्सीत्-अतर्पीत्-अत्राप्सीत्-अतृपत् । 'दृप ११९७ हर्षमोहनयोः' । मोहनं गर्वः । दृप्यतीत्यादि ।

'रधादित्वादिमौ वेट्कावमर्थमनुदात्तता' ।

'द्रुह ११९८ जिघांसायाम् । 'वा द्रुहमुह-' (सू ३२७) इति वा घः । पक्षे ढः । दुद्रोग्ध-दुद्रोढ-दुद्रोहिथ । द्रोहिता-द्रोग्धा-द्रोढा । द्रोहिष्यति-ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् । 'मुह ११९९ वैचित्त्ये' । वैचित्त्यमविवेकः । मुह्यति । मुमोहिथ-मुमोग्ध-मुमोढ । मोग्धा-मोढा-मोहिता । मोहिष्यति-मोक्ष्यति । अमुहत् । 'ष्णुह १२०० उद्गिरणे' । स्नुह्यति । सुष्णोह । सुष्णोहिथ-सुष्णोग्ध-सुष्णोढ । सुष्णुहिव-सुष्णुह्व । स्नोहिता-स्नोग्धा-स्नोढा । स्नोहिष्यति-स्नोक्ष्यति । अस्नुहत् । 'ष्णिह १२०१ प्रीतौ' । स्निह्यति । सिष्णेह । वृत् । रधादयः समाप्ताः । पुषादयस्तु आगणान्तादिति सिद्धान्तः । 'शमु १२०२ उपशमे' ।

२५१९ । शमामष्टानां दीर्घः श्यनि । ७ । ३ । ७४ । शमादीनामित्यर्थः । प्रशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् । 'तमु १२०३ काङ्क्षायाम्' । ताम्यति । तमिता । अतमत् । 'दमु १२०४ उपशमे' । उपशम इति ण्यन्तस्य । तेन सकर्मकोऽयम् । न तु शमिवदकर्मकः । अदमत् । 'श्रमु १२०५ तपसि खेदे च' । श्राम्यति । अश्रमत् । 'भ्रमु १२०६ अनवस्थाने' । 'वा भ्राश-' (सू २३२१) इति श्यन्वा । तत्र कृते 'शमामष्टानाम्-' (सू २५१९) इति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् । 'क्षमू १२०७ सहने' । क्षाम्यति । चक्षमिथ-चक्षन्थ । चक्षमिव-चक्षण्व । चक्षमिम-चक्षण्म । क्षमिता-क्षन्ता । अयमषित् । भ्वादिस्तु षित् ।

'अषितः क्षाम्यतेः क्षान्तिः क्षमूषः क्षमतेः क्षमा' ।

'क्लमु १२०८ ग्लानौ' । क्लाम्यति-क्लामति । शपीव श्यन्यापि 'ष्ठिवुक्लमु-' (सू २३२०) इत्येव दीर्घे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् । 'मदी १२०९ हर्षे' । माद्यति । अमदत् । शमादयोऽष्टौ गताः ।

'असु १२१० क्षेपणे' । अस्यति । आस । असिता ।

२५२० । अस्यतेस्थुक् । ७ । ४ । १७ । अङि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे 'अस्यतिवक्ति-' (सू २४३८) इति वचनं तङर्थम् । तङ् तु 'उपसर्गादस्यत्यूह्योर्वा' इति वक्ष्यते । पर्यास्थत । 'यसु १२११ प्रयत्ने' ।

२५२१ । यसोऽनुपसर्गात् । ३ । १ । ७१ ।

२५२२ । संयसश्च । ३ । १ । ७२ । श्यन्वा स्यात् । यस्यति-यसति । संयस्यति-संयसति । 'अनुपसर्गात्' किम् । प्रयस्यति । 'जसु १२१२ मोक्षणे' । जस्यति । 'तसु १२१३ उपक्षये' । 'दसु १२१४ च' । तस्यति । अतसत् । दस्यति । अदसत् । 'वसु १२१५ स्तम्भे'

वत्स्यति । ववास । ववसतुः । 'न शसदद–' (सू २२६३) इति निषेधः । वशादिरयमिति मते तु । वेसतुः । वेसुः । 'व्युष १२१६ विभागे' । अयं दाहे पठितः । अर्थभेदेन त्विहार्थं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्त्योऽयम् 'व्युसति' इत्यन्ये । अयकारं 'वुस' इत्यपरे । 'प्लुष १२१७ दाहे' । अप्लुषत् । पूर्वत्रपाठः सिजर्थ इत्याहुः । तद्भ्वादिपाठेन गतार्थमिति सुवचम् । 'विस १२१८ प्रेरणे' । विस्यति । अविसत् । 'कुस १२१९ संश्लेषणे' । अकुसत् । 'बुस १२२० उत्सर्गे' । 'मुस १२२१ खण्डने' । 'मसी १२२२ परिणामे' । परिणामो विकारः । 'समी' इत्येके । 'लुठ १२२३ विलोडने' । 'उच १२२४ समवाये' । उच्यति । उवोच । ऊचतुः । मा भवानुचत् । 'भृशु १२२५ भ्रंशु १२२६ अधःपतने' । बभर्श । अभृशत् । 'अनिदिताम्–'(सू ४१५) इति नलोपः । भ्रश्यति । अभ्रशत् । 'वृश १२२७ वरणे' । वृश्यति । अवृशत् । 'कृश १२२८ तनूकरणे' । कृश्यति । 'ञितृष १२२९ पिपासायाम्' । 'हृष १२३० तुष्टौ' । श्यन्नङौ भौवादिकाद्विशेषः । 'रुष १२३१ रिष १२३२ हिंसायाम्' । 'तीषसह–'(सू २३४०) इति वेट् । रोषिता–रोष्टा । रेषिता–रेष्टा । 'डिप १२३३ क्षेपे' । 'कुप १२३४ क्रोधे' । 'गुप १२३५ व्याकुलत्वे' । 'युपु १२३६ रुपु १२३७ लुपु १२३८ विमोहने' । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् । 'लुभ १२३९ गार्ध्ये' । गार्ध्यमाकाङ्क्षा । 'तीषसह–'(सू २३४०) इति वेट् । लोभिता–लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् । भ्वादेरवृत्कृतत्वाल्लोभतीत्यपीत्याहुः । 'क्षुभ १२४० संचलने' । क्षुभ्यति । 'णभ १२४१ तुभ १२४२ हिंसायाम्' । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । क्र्यादित्वात्पक्षे सिद्भवत्येव । इह पाठस्तु श्यन्नर्थः । 'क्लिदू १२४३ आर्द्रीभावे' । क्लिद्यति । चिक्लेदिथ–चिक्लेत्थ । चिक्लिदिव–चिक्लिद्व । चिक्लिदिम–चिक्लिद्म । क्लेदिता–क्लेत्ता । 'ञिमिदा १२४४ स्नेहने' । 'मिदेर्गुणः' (सू २३४६) । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति मा भूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः । 'ञिक्ष्विदा १२४५ स्नेहनमोचनयोः' । 'ऋधु १२४६ वृद्धौ' । आनर्ध । आर्धत् । 'गृधु १२४७ अभिकाङ्क्षायाम्' । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् । दिवादिस्तु भ्वादिवदाकृतिगणः । तेन क्षीयते मृग्यतीत्यादि सिद्धिरित्याहुः ।

इति तिङन्तदिवादिप्रकरणम् ।

अथ तिङन्तस्वादिप्रकरणम् ।

'षुञ् १२४८ अभिषवे' । अभिषवः स्नपनं पीडनं स्नानं सुरासंधानं च । तत्र स्नानेऽकर्मकः ।

२५२३ । स्वादिभ्यः श्नुः । ३ । १ । ७३ । सुनोति । सुनुतः । 'हुश्नुवोः–' (सू २३८७) इति यण् । सुन्वन्ति । सुन्वः–सुनुवः । सुन्वहे–सुनुवहे । सुषाव–सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् । 'स्तुसुधूञ्भ्यः–' (सू २३८५) इतीट् । असावीत्–असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ।

२५२४ । सुनोतेः स्यसनोः । ८ । ३ । ११७ । स्ये सनि च परे सुञः षो न स्यात् । विसोष्यति । 'षिञ् १२४९ बन्धने' । सिनोति । विसिनोति । सिषाय–सिष्ये । सेता । 'शिञ्

१२५० निशाने'। तालव्यादिः। शेता। 'डुमिञ् १२५१ प्रक्षेपणे'। 'मीनातिमिनोति-' (सू २५०८) इत्यात्वम्। ममौ। ममिथ-ममाथ। मिम्ये। माता। मीयात्। मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त। 'चिञ् १२५२ चयने'। प्रणिचिनोति।

२५२५। विभाषा चेः। ७। ३। ५८। अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च। प्रणिचिकाय। चिचाय-चिक्ये-चिच्ये। अचैषीत्-अचेष्ट। 'स्तृञ् १२५३ आच्छादने'। स्तृणोति। स्तृणुते। 'गुणोऽर्ति-' (सू २३८०) इति गुणः। स्तर्यात्।

२५२६। ऋतश्च संयोगादेः। ७। २। ४३। ऋदन्तात्संयोगादेः परयोर्लिङ्सिचोरिड्वा स्यात्तङि। स्तरिषीष्ट-स्तृषीष्ट। अस्तरिष्ट-अस्तृत। 'कृञ् १२५४ हिंसायाम्'। कृणोति-कृणुते। चकार। चकर्थ। चक्रे। क्रियात्। कृषीष्ट। अकार्षीत्। अकृत। 'वृञ् १२५५ वरणे'।

२५२७। बभूथाततन्थजगृभ्मववर्थेति निगमे। ७। २। ६४। एषां वेद इडभावो निपात्यते। तेन भाषायां थलीट्। ववरिथ। ववृव। ववृवहे। वरिता-वरीता।

२५२८। लिङ्सिचोरात्मनेपदेषु। ७। २। ४२। वृङ्वृञ्भ्यामृदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि।

२५२९। न लिङि। ७। २। ३९। वृतो लिङ इटो दीर्घो न स्यात्। वरिषीष्ट-वृषीष्ट। अवारीत्। अवरिष्ट-अवरीष्ट-अवृत। 'धुञ् १२५६ कम्पने'। धुनोति-धुनुते। अधौषीत्। अधोष्यत्। दीर्घान्तोऽप्ययम्। धूनोति-धूनुते। स्वरतिसूति-' (सू २२७९) इति वेट्। दुधविथ-दुधोथ। किती लिटि तु 'श्र्युकः-' (सू २३८१) इति निषेधं बाधित्वा क्रादिनियमान्नित्यामिट्। दुधुविव। 'स्तुसुधूञ्भ्यः-' (सू २३८५) इति नित्यमिट्। अधावीत्। अधविष्ट-अधोष्ट।

अथ परस्मैपदिनः। 'टुदु १२५७ उपतापे'। दुनोति। 'हि १२५८ गतौ वृद्धौ च'।

२५३०। हिनुमिना। ८। ४। १५। उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात्। प्रहिणोति।

२५३१। हेरचङि। ७। ३। ५६। अभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्न तु चङि। जिघाय। 'पृ १२५९ प्रीतौ'। पृणोति। पर्ता। 'स्पृ १२६० प्रीतिपालनयोः'। 'प्रीतिचलनयोः' इत्यन्ये। 'चलनं जीवनम्'। इति स्वामी। स्पृणोति। पस्पार। 'स्मृ' इत्येके। स्मृणोति। पृणोतिप्रभृतयस्त्रयोऽपि छान्दसा इत्याहुः। 'आप्लृ १२६१ व्याप्तौ'। आप्नोति। आप्नुतः। आप्नुवन्ति। आप्नुवः। आप्ता। आप्नुहि। ऌदित्त्वादङ्। आपत्। 'शक्लृ १२६२ शक्तौ'। अशकत्। 'राध १२६३ साध १२६४ संसिद्धौ'। राध्नोति।

२५३२। राधो हिंसायाम्। ६। ४। १२३। एत्त्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च। रेधतुः। रेधुः। रेधिथ। राद्धा। साध्नोति। साद्धा। असात्सीत्। असाद्धाम्।

अथ द्वावनुदात्तेतौ। 'अशू १२६५ व्याप्तौ संघाते च'। अश्नुते।

२५३३। अश्नोतेश्च। ७। ४। ७२। दीर्घादभ्यासादवर्णात्परस्य नुट् स्यात्। आनशे। अशिता-अष्टा। अशिष्यते-अक्ष्यते। अश्नुवीत। अक्षीष्ट-आशिषीष्ट। आशिष्ट-आष्ट। आक्षाताम्। 'ष्टिघ १२६६ आस्कन्दने'। स्तिघ्नुते। तिष्टिघे। स्तेघिता।

अथ आ गणान्तात्परस्मैपदिनः। 'तिक १२६७ तिग १२६८ गतौ च'। नादास्कन्दने

तिक्नोति । तिघ्नोति । 'षघ १२६९ हिंसायाम्' । सघ्नोति । 'ञिधृषा १२७० प्रागल्भ्ये' । धृष्णोति । दधर्ष । धर्षिता 'दन्भु १२७१ दम्भने' । दम्भनं दम्भः । दभ्नोति । ददम्भ । 'श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वा' इति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । 'अनिदिताम्–' (सू ४१५) इति नलोपः । तस्याभीयत्वादसिद्धत्वेन एत्त्वाभ्यासलोपयोरप्राप्तौ । 'दम्भेश्च एत्त्वाभ्यासलोपौ वक्तव्यौ' (वा ४१५३) । देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिम्मिप्सु । देभ । देभिथ । 'देभ' इति रूपान्तरं बोध्यम् । अपिद्विषयकमिति न्यासकारादिमते तु । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् । 'ऋधु १२७२ वृद्धौ' । 'तृप प्रीणने' इत्येके । क्षुभ्नादित्वाण्णत्वं न । तृप्नोति । 'छन्दसि' (गण १९७) । आगणान्ताधिकारोऽयम् । 'अह १२७३ व्याप्तौ' । अह्नोति । 'दघ १२७४ घातने पालने च' । दघ्नोति । 'चमु १२७५ भक्षणे' । चम्नोति । 'रि १२७६ क्षि १२७७ चिरि १२७८ जिरि १२७९ दाश १२८० दृ १२८१ हिंसायाम्' । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । 'न तद्यशः शस्त्रभृतां क्षिणोति' । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । दृणोति । वृत् ।

इति तिङन्तस्वादिप्रकरणम् ।

अथ तिङन्ततुदादिप्रकरणम् ।

'तुद १२८२ व्यथने' । इतः षट् स्वरितेतः ।

२५३४ । तुदादिभ्यः शः । ३ । १ । ७७ । तुदति–तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत्–अतुत्त । 'णुद १२८३ प्रेरणे' । नुदति–नुदते । नुनोद–नुनुदे । नोत्ता । 'दिश १२८४ अतिसर्जने' । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत्–अदिक्षत । 'भ्रस्ज १२८५ पाके । 'ग्रहिज्या–' (सू २४१२) इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति–भृज्जते ।

२५३५ । भ्रस्जो रोपधयो रमन्यतरस्याम् । ६ । ४ । ४७ । भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्त्वादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ–बभर्ष्ठ । बभर्जे । रमभावे बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । 'स्कोः–' (सू ३८०) इति सलोपः । 'व्रश्च–' (सू २९४) इति षः । बभ्रष्ठ । बभ्रज्जे । भर्ष्टा–भ्रष्टा । भ्रक्ष्यति–भर्क्ष्यति । 'क्ङिति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन' (वा ४०७८) । भृज्ज्यात् । भृज्ज्यास्ताम् । भर्क्षीष्ट–भ्रक्षीष्ट । अभार्क्षीत्–अभ्राक्षीत् । अभर्ष्ट–अभ्रष्ट । 'क्षिप १२८६ प्रेरणे' । क्षिपति–क्षिपते । क्षेप्ता । अक्षैप्सीत्–अक्षिप्त । 'कृष १२८७ विलेखने' । कृषति–कृषते । क्रष्टा–कर्ष्टा । कृष्यात् । कृक्षीष्ट । 'स्पृशमृशकृष–' इति सिज्वा । पक्षे क्सः । सिचि अम्वा । अक्राक्षीत्–अकार्क्षीत्–अकृक्षत् । तङि 'लिङ्सिचौ–' (सू २३००) इति कित्त्वादम्न । अकृष्ट । अकृक्षाताम् । अकृक्षत । अकृक्षाताम् । अकृक्षन्त । 'ऋषी १२८८ गतौ' । परस्मैपदी । ऋषति । आनर्ष । 'जुषी १२८९ प्रीतिसेवनयोः' । आत्मनेपदिनश्चत्वारः । जुषते । 'ओविजी १२९० भयचलनयोः' । प्रायेणायमुत्पूर्वः । उद्विजते ।

२८३६ । विज इट् । १ । २ । २ । विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्वि-
ज्यते । 'ओलजी १२९१ ओलस्जी १२९२ व्रीडायाम्' । लजते । लेजे । लज्जते । लज्जे ।
अथ परस्मैपादिनः । 'ओव्रश्चू १२९३ छेदने' । 'ग्रहिज्या–' (सू २४१२) । वृश्चति । वव्रश्च ।
वव्रश्चतुः । वव्रश्चिथ–वव्रष्ठ । 'लिट्यभ्यासस्य–' (सू २४०८) इति संप्रसारणम् । रेफस्य ऋकार
'उरत्' (सू २२४४) । तस्य 'अचः परस्मिन्–' (सू ५०) इति स्थानिवद्भावात् 'न संप्रसारणे–'
(सू ३६३) इति वस्योत्वं न । व्रश्चिता–व्रष्टा । व्रश्चिष्यति–व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत्
अव्राक्षीत् । 'व्यच १२९४ व्याजीकरणे' । विचति । विव्याच । विविचतुः । व्यचिता । व्यचि-
ष्यति । विच्यात् । अव्याचीत्–अव्यचीत् । 'व्यचेः कुटादित्वमनसि' (वा ३४९६) इति
नेह प्रवर्तते । 'अनसि' इति पर्युदासेन कृन्मात्रविषयत्वात् । 'उछि १२९५ उञ्छे' । उञ्छ-
ति । 'उछी १२९६ विवासे' । उच्छति । 'ऋछ १२९७ गतीन्द्रियप्रलयमूर्तिभावेषु' । 'ऋच्छ-
त्यृताम्' (सू २३८३) इति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्च्छ । आन-
र्च्छतुः । ऋच्छिता । 'मिछ १२९८ उत्क्लेशे' । उत्क्लेशः पीडा । मिमिच्छ । अमिच्छी-
'जर्ज १२९९ चर्च १३०० झर्झ १३०१ परिभाषणभर्त्सनयोः' । 'त्वच १३०२ संवरणे'
तत्वाच । 'ऋच १३०३ स्तुतौ' । आनर्च । 'उब्ज १३०४ आर्जवे' । 'उज्झ १३०५ उत्सर्गे'
'लुभ १३०६ विमोहने' । विमोहनमाकुलीकरणम् । लुभति । लोभिता–लोब्धा । लोभि-
ष्यति । 'रिफ १३०७ कत्थनयुद्धनिन्दाहिंसादानेषु' । रिफति । रिरेफ । 'रिह' इत्येके
'शिशुं न विप्रा मतिभी रिहन्ति' । 'तृप १३०८ तृम्फ १३०९ तृप्तौ' । आद्यः प्रथमान्तः
द्वितीयो द्वितीयान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता । 'स्पृशमृश–' इति
सिज्विकल्पः पौषादिकस्यैव अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । ...
ङित्त्वात् 'अनिदिताम्–' (सू ४१५) इति नलोपे । 'शे तृम्फादीनां नुम्वाच्यः' (वा ...)
आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फन्ति । ततृम्फ । तृम्...
'तुप १३१० तुम्प १३११ तुफ १३१२ तुम्फ १३१३ हिंसायाम्' । तुपति । तुम्पति । तुफति ।
तुम्फति । 'दृप १३१४ दृम्फ १३१५ उत्क्लेशे' । प्रथमः प्रथमान्तः । द्वितीयो द्वितीयान्तः
प्रथमो द्वितीयान्त इत्येके । दृपति । दृफति । दृम्फति । 'ऋफ १३१६ ऋम्फ १३१७ हिंसायाम्'
ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार । 'गुफ १३१८ गुम्फ १३१९ ग्रन्थे' । गुफति ।
जुगोफ । गुम्फति । जुगुम्फ । 'उभ १३२० उम्भ १३२१ पूरणे' । उभति । उवोभ । उम्भति ।
उम्भांचकार । 'शुभ १३२२ शुम्भ १३२३ शोभार्थे' । शुभति । शुम्भति । 'दृभी १३२४
ग्रन्थे' । दृभति । 'चृती १३२५ हिंसाग्रन्थनयोः' । चर्तिता । 'सेऽसिचि–' (सू२५०६) इति
वेट् । चर्तिष्यति–चर्त्स्यति । अचर्तीत् । 'विध १३२६ विधाने' । विधति । वेधिता
'जुड १३२७ गतौ' । तवर्गपञ्चमान्त इत्येके । जुडति । 'मरुतो जुनन्ति' । 'मृड १३२८
सुखने' । मृडति । मर्डिता । 'पृड १३२९ च' । पृडति । 'पृण १३३० प्रीणने' । पृणति ।
पपर्ण । 'वृण १३३१ च' । वृणति । 'मृण १३३२ हिंसायाम्' । 'तुण १३३३ कौटिल्ये'
तुतोण । 'पुण १३३४ कर्मणि शुभे' । पुणति । 'मुण १३३५ प्रतिज्ञाने' । 'कुण १३३६
शब्दोपकरणयोः' । 'शुन १३३७ गतौ' । 'द्रुण १३३८ हिंसागतिकौटिल्येषु' । 'घुण १३३९
घूर्ण १३४० भ्रमणे' । 'षुर १३४१ ऐश्वर्यदीप्त्योः' । सुरति । सुषोर । आशिषि सूर्यात् ।

१३४२ शब्दे'। कुरति। कूर्यात्। अत्र 'न भकुर्छुराम्' (सू १६२९) इति निषेधो न। करोतेरेव तत्र ग्रहणादित्याहुः। 'खुर १३४३ छेदने'। 'मुर १३४४ संवेष्टने'। 'क्षुर १३४५ विलेखने'। घुर १३४६ भीमार्थशब्दयोः'। 'पुर १३४७ अग्रगमने'। वृहू १३४८ उद्यमने'। दन्त्योष्ठ्यादिः। पवर्गीयादिरित्यन्ये। तृहू १३४९ स्तृहू १३५० तृंहू १३५१ हिंसार्थाः'। तृहति। ततर्ह। स्तृहति। तस्तर्ह। तर्हिता–तर्ढा। स्तर्हिता–स्तर्ढा। अतृंहीत्–अताङ्क्षीत्। अताण्ढाम्। 'इष १३५२ इच्छायाम्'। 'इषुगमि–' (सू २४००) इति छः। इच्छति। एषिता–एष्टा। एषिष्यति। इष्यात्। ऐषीत्। 'मिष १३५३ स्पर्धायाम्'। मिषति। मेषिता। 'किल १३५४ श्वैत्यक्रीडनयोः'। 'तिल १३५५ स्नेहे'। 'चिल १३५६ वसने'। 'चल १३५७ विलसने'। 'इल १३५८ स्वप्नक्षेपणयोः'। 'विल १३५९ संवरणे'। दन्त्योष्ठ्यादिः। 'बिल १३६० भेदने'। ओष्ठ्यादिः। 'णिल १३६१ गहने'। 'हिल १३६२ भावकरणे'। 'शिल १३६३ षिल १३६४ उञ्छे'। 'मिल १३६५ श्लेषणे'। 'लिख १३६६ अक्षरविन्यासे'। लिलेख। 'कुट १३६७ कौटिल्ये'। 'गाङ्कुटादिभ्यः–' (सू २४६१) इति ङित्त्वम्। चुकुटिथ। चुकोट। चुकुट। कुटिता। 'पुट १३६८ संश्लेषणे'। 'कुच १३६९ संकोचने'। 'गुज १३७० शब्दे'। 'गुड १३७१ रक्षायाम्'। 'डिप १३७२ क्षेपे'। 'छुर १३७३ छेदने'। 'न भकुर्छुराम्' (सू१६२९) इति न दीर्घः। छुर्यात्। 'स्फुट १३७४ विकसने'। स्फुटति। पुस्फोट। 'मुट १३७५ आक्षेपमर्दनयोः'। 'त्रुट १३७६ छेदने'। 'वा भ्राश–' (सू २३२१) इति श्यन्वा। त्रुट्यति–त्रुटति। तुत्रोट। त्रुटिता। 'तुट १३७७ कलहकर्मणि'। तुटति। तुतोट। तुटिता। 'चुट १३७८ छुट १३७९ छेदने'। 'जुट १३८० बन्धने'। 'कड १३८१ मदे'। 'लुट १३८२ संश्लेषणे'। 'कृड १३८३ घनत्वे'। घनत्वं सान्द्रता। चकर्ड। कृडिता। 'कुड १३८४ बाल्ये'। 'पुड १३८५ उत्सर्गे'। 'घुट १३८६ प्रतिघाते'। 'तुड १३८७ तोडने'। तोडनं भेदः। 'थुड १३८८ स्थुड १३८९ संवरणे'। थुडति। तुथोड। तुष्ठोड। 'खुड छुड' इत्येके। 'स्फुर १३९० फुल १३९१ संचलने'। 'स्फुर स्फुरणे' 'स्फुल संचलने' इत्येके।

२५३७। स्फुरतिस्फुलत्योर्निर्निविभ्यः। ८। ३। ७६। षत्वं वा स्यात्। निष्फुरति–निःस्फुरति। 'स्फर' इत्यकारोपधं केचित्पठन्ति। पस्फार। 'स्फुड १३९२ चुड १३९३ व्रुड १३९४ संवरणे'। 'क्रुड १३९५ भृड १३९६ निमज्जने' इत्येके। 'गुरी १३९७ उद्यमने'। अनुदात्तेत्। गुरते। जुगुरे। गुरिता। 'णू १३९८ स्तवने'। दीर्घान्तः। 'परिणूतगुणोदयः'। इतश्चत्वारः परस्मैपदिनः। नुवति। अनुवीत्। 'धू १३९९ विधूनने'। धुवति। 'गु १४०० पुरीषोत्सर्गे'। जुगुविथ–जुगुथ। गुता। गुष्यति। अगुषीत्। 'ह्रस्वादङ्गात्' (सू २३६९)। अगुताम्। अगुषुः। 'ध्रु १४०१ गतिस्थैर्ययोः'। 'ध्रुव' इति पाठान्तरम्। आद्यस्य ध्रुवतीत्यादि गुवतिवत्। द्वितीयस्तु सेट्। दुध्रुविथ। ध्रुविता। ध्रुविष्यति। ध्रुव्यात्। अध्रुवीत्। अध्रुविष्टाम्। 'कुङ् १४०२ शब्दे'। 'दीर्घान्तः' इति कैयटादयः। कुविता। अकुविष्ट। 'ह्रस्वान्तः' इति न्यासकारः। कुता। अकुत। वृत्। कुटादयो वृत्ताः।

'पृङ् १४०३ व्यायामे'। प्रायेण व्याङ्पूर्वः। रिङ्। इयङ्। व्याप्रियते। व्यापप्रे। व्यापप्राते। व्यापरिष्यते। व्यापृत। व्यापृषाताम्। 'मृङ् १४०४ प्राणत्यागे'।

२५३८। म्रियतेर्लुङ्लिङोश्च। १। ३। ६१। लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्त-

ङ्गान्यत्र। ङित्त्वं स्वरार्थम्। म्रियते। ममार। मम्र्थ। मम्रिव। मर्तासि। मरिष्यति। मृषीष्ट। अमृत।

अथ परस्मैपादिनः सप्त। 'रि १४०५ पि १४०६ गतौ'। लघूपधगुणादन्तरङ्गत्वादियङ्। रियति। पियति। रेता। पेता। 'धि १४०७ धारणे'। 'क्षि १४०८ निवासगत्योः'। 'षू १४०९ प्रेरणे'। सुवति। सविता। 'कॄ १४१० विक्षेपे'। किरति। किरतः। चकार। चकरतुः। करिता-करीता। कीर्यात्। अकारीत्।

२५३९। किरतौ लवने। ६। १। १४०। उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे। उपस्किरति। 'अड्भ्यासव्यवायेऽपि सुट् कात्पूर्वं इति वक्तव्यम्' (वा ३६९९)। उपास्किरत्। उपचस्कार।

२५४०। हिंसायां प्रतेश्च। ६। १। १४१। उपात्प्रतेश्च किरतेः सुट् स्याद्धिंसायाम्। उपस्किरति। प्रतिस्किरति। 'गॄ १४११ निगरणे'।

२५४१। अचि विभाषा। ८। २। २१। गिरते रेफस्य लत्वं वा स्यादजादौ। गिरति-गिलति। जगार-जगाल। जगरिथ। जगलिथ। गरिता-गलिता। 'दृङ् १४१२ आदरे'। आद्रियते। आद्रियेते। आदद्रे। अदद्रिषे। आदर्ता। आदरिष्यते। आदृषीष्ट। आदृत। आदृषाताम्। 'धृङ् १४१३ अवस्थाने'। ध्रियते।

अथ परस्मैपादिनः षोडश। 'प्रच्छ १४१४ ज्ञीप्सायाम्'। पृच्छति। पप्रच्छ। पप्रच्छतुः। पप्राच्छिथ-पप्रष्ठ। प्रष्टा। प्रक्ष्यति। अप्राक्षीत्। वृत्। किरादयो वृत्ताः। 'सृज १४१५ विसर्गे'। 'विभाषा सृजिदृशोः' (सू २४०४)। ससर्जिथ-सस्रष्ठ। स्रष्टा। स्रक्ष्यति। 'सृजिदृशोर्झल्यमकिति' (सू २४०५) इत्यमागमः। सृजेत्। सृज्यात्। अस्राक्षीत्। 'टुमस्जो १४१६ शुद्धौ'। मज्जति। ममज्ज। 'मस्जिनशोर्झलि (सू २५१७) इति नुम्। 'मस्जेरन्त्यात्पूर्वो नुम्वाच्यः (वा ३२१)। संयोगादिलोपः। ममङ्क्थ। ममज्जिथ। मङ्क्ता। मङ्क्ष्यति। अमाङ्क्षीत्। अमाङ्क्ताम्। अमाङ्क्षुः। 'रुजो १४१७ भङ्गे'। रोक्ता। रोक्ष्यति। अरौक्षीत्। अरौक्ताम्। 'भुजो १४१८ कौटिल्ये'। रुजिवत्। 'छुप १४१९ स्पर्शे'। छोप्ता। अच्छौप्सीत्। 'रुश १४२० रिश १४२१ हिंसायाम्'। तालव्यान्तौ। रोष्टा। रोक्ष्यति। रेष्टा। रेक्ष्यति। 'लिश १४२२ गतौ'। अलिक्षत्। 'स्पृश १४२३ संस्पर्शने'। स्प्रष्टा-स्पर्ष्टा। स्प्रक्ष्यति-स्पर्क्ष्यति। अस्प्राक्षीत्-अस्पार्क्षीत्-अस्पृक्षत्। 'विच्छ १४२४ गतौ'। 'गुपूधूप-' (सू२३०२) इत्याय आर्धधातुके वा। विच्छायति। विच्छायांचकार-विविच्छ। 'विश १४२५ प्रवेशने'। विशति। वेष्टा। 'मृश १४२६ आमर्शने'। आमर्शनं स्पर्शः। अम्राक्षीत्-अमार्क्षीत्-अमृक्षत्। 'णुद १४२७ प्रेरणे'। कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः। 'षद्लृ १४२८ विशरणगत्यवसादनेषु'। 'सीदति' इत्यादि भौवादिकवत्। इह पाठो नुम्विकल्पार्थः। सीदती-सीदन्ती। ज्वलादौ पाठस्तु णार्थः। सादः। स्वरार्थश्च। शवनुदात्तः। शस्तूदात्तः। 'शद्लृ १४२९ शातने'। स्वरार्थ एव पुनः पाठः। शता तु नास्ति। 'शदेः शितः' (सू २३६२) इत्यात्मनेपदविधेः।

अथ षट् स्वरितेतः। 'मिल १४३० संगमे'। 'मिल संश्लेषणे' इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः। मिलति-मिलते। मिमेल-मिमिले। 'मुच्लृ १४३१ मोक्षणे'।

२५४२। शे मुचादीनाम्। ७। १। ५९। नुम्स्यात्। मुञ्चति। मुञ्चते। मोक्ता।

मुच्यात् । मुक्षीष्ट । अमुचत्-अमुक्त । अमुक्षाताम् । 'लुपॢ १४३२ छेदने' । लुम्पति-लुम्पते । अलुपत्-अलुप्त । 'विदॢ १४३३ लाभे' । विन्दति-विन्दते । विवेद-विविदे । व्याघ्रभूत्यादिमते सेडयम् । वेदिता । भाष्यादिमतेऽनिट्कः । वेत्ता । परिवेत्ता । परिवर्जने । ज्येष्ठं परित्यज्य दारानग्नींश्च लब्धवानित्यर्थः । तृन्तृचौ । 'लिप १४३४ उपदेहे' । उपदेहो वृद्धिः । लिम्पति-लिम्पते । लेता । 'लिपिसिचि-'(सू २४१८) इत्यङ् । तङि तु वा । अलिपत् । अलिपत-अलिप्त । 'षिच १४३५ क्षरणे' । सिञ्चति-सिञ्चते । असिचत्-असिचत-असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषेच ।

अथ त्रयः परस्मैपदिनः । 'कृती १४३६ छेदने' । कृन्तति । चकर्त । कर्तिता । कर्तिष्यति-कर्त्स्यति । अकर्तीत् । 'खिद १४३७ परिघाते' । खिन्दति । चिखेद । खेत्ता । अयं दैन्ये दिवादौ रुधादौ च । 'पिश १४३८ अवयवे' । पिंशति । पेशिता । अयं दीपनायामपि । 'त्वष्टा रूपाणि पिंशतु' । वृत् । मुचादयस्तुदादयश्च ।

इति तिङन्ततुदादिप्रकरणम् ।

अथ तिङन्तरुधादिप्रकरणम् ।

'रुधिर् १४३९ आवरणे' । नव स्वरितेत इरितश्च ।

२५४३ । रुधादिभ्यः श्नम् । ३ । १ । ७८ । शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि । 'श्नसोरल्लोपः' (सू २४६९) । णत्वस्यासिद्धत्वादनुस्वारः । परसवर्णः । तस्यासिद्धत्वाण्णत्वं न । 'न पदान्त-' (सू ५१) इति सूत्रेणानुस्वारपरसवर्णयोरल्लोपे न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रोत्स्यते । रुणद्धु । रुन्ध्यात् । रुन्धि । रुणधानि । रुणधै । अरुणत् । अरुन्धाम् । अरुणत् । अरुणः । अरुणधम् । अरुधत्-अरौत्सीत् । अरुद्ध । 'भिदिर् १४४० विदारणे' । भिनत्ति । भिन्ते । भेत्ता । भेत्स्यति । अभिनत्-अभिनः । अभिनदम् । अभिन्त । अभिदत्-अभैत्सीत् । अभित्त । 'छिदिर् १४४१ द्वैधीकरणे' । अच्छिदत्-अच्छैत्सीत्-अच्छित्त । रिचिर् १४४२ विरेचने' । 'रिणक्ति । रिङ्क्ते । रिरेच-रिरिचे । रेक्ता । अरिणक् । अरिचत्-अरैक्षीत् । अरिक्त । 'विचिर् १४४३ पृथग्भावे' । विनक्ति-विङ्क्ते । 'क्षुदिर् १४४४ संपेषणे' । क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत्-अक्षौत्सीत् । अक्षुत्त । 'युजिर् १४४५ योगे' । योक्ता । 'उच्छृदिर् १४४६ दीप्तिदेवनयोः' । छृणत्ति । छृन्ते । चच्छर्द । 'सेऽसिचि-' (सू २५०६) इति वेट् । चच्छृदिषे-चच्छृत्से । छर्दिता । छर्दिष्यति-छर्त्स्यति । अच्छृदत्-अच्छर्दीत् । अच्छर्दिष्ट । 'उतृदिर् १४४७ हिंसानादरयोः' । तृणत्तीत्यादि । 'कृती १४४८ वेष्टने' । परस्मैपदी । कृणत्ति । आर्धधातुके तौदादिकवत् । 'ञिइन्धी १४४९ दीप्तौ' । त्रय आत्मनेपदिनः ।

२५४४ । श्नान्नलोपः । ६ । ४ । २३ । श्नमः परस्य नस्य लोपः स्यात् (सू २४६९) । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः । 'खिद १४५० दैन्ये' । खिन्ते । खेत्ता । 'विद १४५१ विचारणे' । विन्ते । वेत्ता ।

अथ परस्मैपदिनः । 'शिषॢ १४५२ विशेषणे' । शिनष्टि । शिंष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेरधिः । जश्त्वम् । 'झरो झरि-' (सू ७१) इति वा डलोपः । अनुस्वारपरसवर्णौ

शिण्ढ–शिण्ड्ढ । शिनषाणि । अशिनट् । लृदित्वादङ् । अशिषत् । 'पिष्लृ १४५३ संचूर्णने' । शिपिवत् । पिनष्टि । 'भञ्जो १४५४ आमर्दने' । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता । 'भुज १४५५ पालनाभ्यवहारयोः' । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् । 'तृह १४५६ हिसि १४५७ हिंसायाम्' ।

२५४५ । तृणह इम् । ७ । ३ । ९२ । तृहः श्नमि कृत इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता । 'उन्दी १४५८ क्लेदने' । उनत्ति । उन्तः । उन्दन्ति । उन्दांचकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् । 'अञ्जू १४५९ व्यक्तिम्रर्षणकान्तिगतिषु' । अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ–आनङ्क्थ । अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् ।

२५४६ । अञ्जेः सिचि । ७ । २ । ७१ । अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् । 'तञ्चू १४६० संकोचने' । तङ्क्ता–तञ्चिता । 'ओविजी १४६१ भयचलनयोः' । विनक्ति । विङ्क्तः । 'विज इट्' (सू २५३६) इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् । 'वृजी १४६२ वर्जने' । वृणक्ति । वर्जिता । 'पृची १४६३ संपर्के' । पृणक्ति । पपर्च ।

इति तिङन्तरुधादिप्रकरणम् ।

अथ तिङन्ततनादिप्रकरणम् ।

अथ सप्त स्वरितेतः । 'तनु १४६४ विस्तारे' । 'तनादिकृञ्भ्य उः' (सू २४६६) । तनोति । तन्वः–तनुवः । तनुते । ततान । तेने । तनु । अतनीत्–अतानीत् ।

२५४७ । तनादिभ्यस्तथासोः । २ । ४ । ७९ । तनादेः सिचो वा लुक्स्यात्तथासोः । थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट–अतानिष्ट । 'अनुदात्तोपदेश–'(सू २४२८) इत्यनुनासिकलोपः । तङि । अतत–अतनिष्ट । अतथाः–अतनिष्ठाः । 'षणु १४६५ दाने' । सनोति–सनुते । 'ये विभाषा' (सू २३१९) । सायात्–सन्यात् । 'जनसन–' (सू २५०४) इत्यात्त्वम् । असात–असनिष्ट । असाथाः–असनिष्ठाः । 'क्षणु १४६६ हिंसायाम्' । क्षणोति । क्षणुते । 'ह्म्यन्त–' (सू २२९९) इति न वृद्धिः । अक्षणीत्–अक्षत–अक्षणिष्ट । अक्षथाः–अक्षणिष्ठाः । 'क्षिणु १४६७ च' । उप्रत्ययनिमित्तो लघूपधगुणः 'संज्ञापूर्वको विधिरनित्यः' (प ९४) इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति–क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित–अक्षेणिष्ट । 'ऋणु १४६८ गतौ' । ऋणोति–अर्णोति । अर्णुतः । अर्णुवन्ति । आनर्ण । आनृणे । अर्णितासि । आर्णीत् । आर्त–आर्णिष्ट । आर्थाः–आर्णिष्ठाः । 'तृणु १४६९ अदने' । तृणोति–तर्णोति । तृणुते–तर्णुते । 'घृणु १४७० दीप्तौ' । जघर्ण । जघृणे ।

अथ द्वावनुदात्तेतौ । 'वनु १४७१ याचने' । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान । 'मनु १४७२ अवबोधने' । मनुते । मेने । 'डुकृञ् १४७३ करणे' । करोति । 'अत उत्सार्वधातुके' (सू२४६७) । कुरुतः । यण् । 'न भकुर्छुराम्' (सू१६१९) इति न दीर्घः । कुर्वन्ति ।

२५४८। नित्यं करोतेः। ६।४।१०८। करोतेः प्रत्ययोकारस्य नित्यं लोपः स्याद्वमयोः परयोः। कुर्वः। कुर्मः। चकर्थ। चकृव। कर्ता। करिष्यति।

२५४९। ये च। ६।४।१०९। कृञ उलोपः स्याद्यादौ प्रत्यये परे। कुर्यात्। आशिषि क्रियात्। कृषीष्ट। अकार्षीत्। 'तनादिभ्यः–' (सू २५४७) इति लुकोऽभावे 'ह्रस्वादङ्गात्' (सू २२६९) इति सिचो लोपः। अकृत। अकृथाः।

२५५०। संपरिभ्यां करोतौ भूषणे। ६।१।१३७।

२५५१। समवाये च। ६।१।१३८। संपरिपूर्वस्य करोतेः सुट् स्याद्भूषणे संघाते चार्थे। संस्करोति। अलंकरोतीत्यर्थः। संस्कुर्वन्ति। संघीभवन्तीत्यर्थः। संपूर्वस्य क्वचिदभूषणेऽपि सुट्। 'संस्कृतं भक्षाः' (सू १२१७) इति ज्ञापकात्। 'परिनिविभ्यः–' (सू २२७५) इति षः। परिष्करोति। 'सिवादीनां वा–' (सू २३५९)। पर्यष्कार्षीत्–पर्यस्कार्षीत्।

२५५२। उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च। ६।१।१३९। उपात्कृञः सुट् स्यादेष्वर्थेषु। चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्यस्याध्याहारः। आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। अलंकृतेत्यर्थः। उपस्कृता ब्राह्मणाः। समुदिता इत्यर्थः। एधो दकस्योपस्कुरुते। गुणाधानं करोतीत्यर्थः। उपस्कृतं भुङ्क्ते। विकृतमित्यर्थः। उपस्कृतं ब्रूते। वाक्याध्याहारेण ब्रूत इत्यर्थः।

२५५३। सुट्कात्पूर्वः। ६।१।१३५। 'अडभ्यासव्यवायेऽपि' इत्युक्तम्। संचस्कार। 'कात्पूर्वः' इत्यादि भाष्ये प्रत्याख्यातम्। तथा हि 'पूर्वं धातुरुपसर्गेण युज्यते'। अन्तरङ्गत्वात्सुट्। ततो द्वित्वम्। एवं च 'ऋतश्च संयोगादेर्गुणः' (सू २३८९)। संचस्करतुः। 'कृसृभृ–' (सू २२९३) सूत्रे 'ऋतो भारद्वाजस्य' (सू २२९६) इति सूत्रे च 'कृञोऽसुट इति वक्तव्यम्' (वा ४४०१)। 'तेन ससुट्कात्परस्येट्। संचस्करिथ। संचस्करिव। 'गुणोऽर्ति–' (सू २३८०) इति सूत्रे 'नित्यं छन्दसि' (सू ३५८७) इति सूत्रात् 'नित्यम्' इत्यनुवर्तते। 'नित्यं यः संयोगादिस्तस्य' इत्यर्थात्सुटि गुणो न। संस्क्रियात्। 'ऋतश्च संयोगादेः' (सू २५२६) इति लिङ्सिचोर्नेट्। 'एकाच उपदेशे–' (सू २२७६) इति सूत्रात् 'उपदेशे' इत्यनुवर्त्य 'उपदेशे यः संयोगादिः' इति व्याख्यानात्। संस्कृषीष्ट। समस्कृत। समस्कृषाताम्।

इति तिङन्ततनादिप्रकरणम्।

अथ तिङन्तक्र्यादिप्रकरणम्।

'डुक्रीञ् १४७४ द्रव्यविनिमये'।

२५५४। क्र्यादिभ्यः श्ना। ३।१।८१। क्रीणाति। 'ई हल्यघोः' (सू २४९७)। क्रीणीतः। ईत्वात्पूर्वं झेरन्तादेशः परत्वान्नित्यत्वादन्तरङ्गत्वाच्च। एवं झस्याद्भावः। ततः 'श्नाभ्यस्तयोः–' (सू २४८३) इत्याल्लोपः। क्रीणन्ति। क्रीणीते। क्रीणाते। क्रीणते। चिक्राय। चिक्रियतुः। चिक्रयिथ–चिक्रेथ। चिक्रियिव। चिक्रियिषे। क्रेता। क्रेष्यति। क्रीयात्। क्रेषीष्ट। अक्रैषीत्। अक्रेष्ट। 'प्रीञ् १४७५ तर्पणे कान्तौ च'। कान्तिः कामना। प्रीणाति–प्रीणीते। 'श्रीञ् १४७६ पाके'। 'मीञ् १४७७ हिंसायाम्'। 'हिनुमीना' (सू २५३०)। प्रमीणाति।

प्रमीणीतः । 'मीनातिमिनोति-' (सू २५०८) इत्येज्विषय आत्त्वम् । ममौ । मिम्यतुः । ममिथ-ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । 'षिञ् १४७८ बन्धने' । सिनाति-सिनीते । सिषाय-सिष्ये । सेता । 'स्कुञ् १४७९ आप्रवणे' ।

२५५५ । स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च । ३ । १ । ८२ । चात् श्ना । स्कुनोति-स्कुनुते । स्कुनाति-स्कुनीते । चुस्काव-चुस्कुवे । स्कोता । अस्कौषीत्-अस्कोष्ट । 'स्तन्भ्वादयश्चत्वारः सौत्राः' । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति-विष्टभ्नाति । अवष्टभ्नोति-अवष्टभ्नाति । अवतष्टम्भ । 'जृस्तम्भु-' (सू २२९१) इत्यङ् वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ।

२५५६ । वेः स्कभ्नातेर्नित्यम् । ८ । ३ । ७७ । वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति । विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ।

२५५७ । हलः श्नः शानज्झौ । ३ । १ । ८३ । हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे 'स्तभ्नुहि' इत्यादि । 'युञ् १४८० बन्धने' । युनाति । युनीते । योता । 'क्नूञ् १४८१ शब्दे' । क्नूनाति-क्नूनीते । क्नविता । 'द्रूञ् १४८२ हिंसायाम्' । द्रूणाति-द्रूणीते । 'पूञ् १४८३ पवने' ।

२५५८ । प्वादीनां ह्रस्वः । ७ । ३ । ८० । शिति परे । पुनाति-पुनीते । पविता । 'लूञ् १४८४ छेदने' । लुनाति । लुनीते । 'स्तॄञ् १४८५ आच्छादने' । स्तृणाति-स्तृणीते । तस्तार । तस्तरतुः । स्तरिता-स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि स्तीर्यात् । 'लिङ्सिचो-' (सू २५२८) इति वेट् । 'न लिङि' (सू २५२९) इति वृत इटो लिङि दीर्घो न स्यात् । स्तरिषीष्ट । 'उश्च' (सू २३६८) इति कित्त्वम् । स्तीर्षीष्ट । 'सिचि च परस्मैपदेषु' (सू २३९२) इति न दीर्घः । अस्तारीत् । अस्तारिष्टाम् । अस्तारिष्ट-अस्तरिष्ट-अस्तीर्ष्ट । 'कॄञ् १४८६ हिंसायाम्' । कृणाति-कृणीते । चकार-चकरे । 'वॄञ् १४८७ वरणे' । वृणाति-वृणीते । ववार-ववरे । वरिता-वरीता । आशिषि 'उदोष्ठ्यपूर्वस्य' (सू २४९४) । वूर्यात् । वरिषीष्ट-वूर्षीष्ट । अवारीत् । अवारिष्टाम् । अवरिष्ट-अवरीष्ट-अवूर्ष्ट । 'धूञ् १४८८ कम्पने' । धुनाति-धुनीते । दुधविथ-दुधोथ । दुधुविव । धोता-धविता । 'स्तुसुधूञ्भ्यः-' (सू २३८५) । इतीट् । अधावीत् । अधविष्ट-अधोष्ट ।

अथ बध्नात्यन्ताः परस्मैपदिनः । 'शॄ १४८९ हिंसायाम्' । 'शॄदॄप्रां ह्रस्वो वा' (सू २४९५) इति ह्रस्वपक्षे यण् । अन्यदा 'ऋच्छत्यॄताम्' (सू २३८३) इति गुणः । शश्रतुः-शशरतुः । 'श्र्युकः किति' (सू २३८१) इति निषेधस्य क्रादिनियमेन बाधः । शशरिव-शश्रिव । शरिता-शरीता । शृणीहि । शीर्यात् । अशारिष्टाम् । 'पॄ १४९० पालनपूरणयोः' । पप्रतुः-पपरतुः । आशिषि पूर्यात् । 'वॄ १४९१ वरणे' । 'भरणे' इत्येके । 'भॄ १४९२ भर्त्सने' । भरणेऽप्येके । 'मॄ १४९३ हिंसायाम्' । मृणाति । ममार । 'दॄ १४९४ विदारणे' । ददरतुः । दद्रुः । 'जॄ १४९५ वयोहानौ' । 'झॄ' इत्येके । 'धॄ' इत्यन्ये । 'नॄ १४९६ नये' । 'कॄ १४९७ हिंसायाम्' ।

'ॠ १४९८ गतौ' । ॠणाति । अरांचकार । अरिता-अरीता । आर्णीत् । आर्णीताम । ईर्यात् । आरीत् । आरिष्टाम् । 'गॄ १४९९ शब्दे' । 'ज्या १५०० वयोहानौ' । 'ग्रहिज्या-(सू २४१२) ।

२५५९ । हलः । ६ । ४ । २ । अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घे कृते । 'प्वादीनां ह्रस्वः' (सू२५५८) । जिनाति । जिज्यौ । जिज्यतुः । 'रीः १५०१ गतिरेषणयोः' । रेषणं वृकशब्दः । 'ली १५०२ श्लेषणे' । 'विभाषा लीयतेः' (सू २५०९) इत्येज्विषय आत्त्वं वा । ललौ-लिलाय । लाता-लेता । 'व्ली १५०३ वरणे' । व्लिनाति । 'प्ली १५०४ गतौ' । वृत् । ल्वादयो वृत्ताः । प्वादयोऽपीत्येके । 'व्री १५०५ वरणे' । 'भ्री १५०६ भये' । 'भरे' इत्येके । 'क्षीष् १५०७ हिंसायाम्' । एषां त्रयाणां ह्रस्वः । केषांचिन्मते तु न । 'ज्ञा १५०८ अवबोधने' । 'ज्ञाजनोर्जा' (सू२५११) । जानाति । दीर्घनिर्देशसामर्थ्यान्न ह्रस्वः । 'बन्ध १५०९ बन्धने' । बध्नाति । बबन्धिथ । बबन्ध । बन्धा । बन्धारौ । भन्त्स्यति । बधान । अभान्त्सीत् । 'पूर्वत्रासिद्धम्' (सू१२) इति भष्भावात्पूर्वं 'झलो झलि' (सू २२८१) इति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न प्रत्ययलक्षणं प्रति सिज्लोपस्यासिद्धत्वात् । अबान्द्धाम् । अभान्त्सुः । 'वृङ् १५१० संभक्तौ' । वृणीते । वव्रे । ववृषे । ववृढ्वे । वरिता-वरीता । अवरिष्ट-अवरीष्ट-अवृत । 'श्रन्थ १५११ विमोचनप्रतिहर्षयोः' । इतः परस्मैपदिनः । श्रथ्नाति । 'श्रन्थिग्रन्थि-' इत्यादिना कित्त्वपक्ष एत्त्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः । श्रेथतुः-श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु शश्राथ-शश्रथेति माधवः । तत्र मूलं मृग्यम् । 'मन्थ १५१२ विलोडने' । 'श्रन्थ १५१३ ग्रन्थ १५१४ संदर्भे' । अर्थभेदाच्छ्रन्थेः पुनः पाठः । रूपं तूक्तम् । 'कुन्थ १५१५ संश्लेषणे' । 'संक्लेशे' इत्येके । कुथ्नाति । चुकुन्थ । 'कुथ' इति दुर्गः । चुकोथ । 'मृद १५१६ क्षोदे' । मृद्नाति । मृदान । 'मृड १५१७ च' । अयं सुखेऽपि । ष्टुत्वम् । मृड्णाति । 'गुध १५१८ रोषे' । गुध्नाति । 'कुष १५१९ निष्कर्षे' । कुष्णाति । कोषिता ।

२५६० । निरः कुषः । ७ । २ । ४६ । निरः परात्कुषो वलादेरार्धधातुकस्य इड्वा स्यात् । निष्कोषिता-निष्कोष्टा । निरकोषीत्-निरकुक्षत् । 'क्षुभ १५२० संचलने' । 'क्षुभ्नादिषु च' (सू७९२) । क्षुभ्नाति । क्षुभ्नीतः । क्षोभिता । क्षुभाण । 'णभ १५२१ तुभ१५२२ हिंसायाम्' । नभ्नाति । तुभ्नाति । 'नभते' 'तोभते' इति शपि । 'नभ्यति' 'तुभ्यति' इति श्यनि । 'क्लिशू १५२३ विबाधने' । 'शात्' (सू११२) इति श्चुत्वनिषेधः । क्लिश्नाति । क्लेशिता-क्लेष्टा । अक्लेशीत्-अक्लिक्षत् । 'अश १५२४ भोजने' । अश्नाति । आश । 'उध्रस १५२५ उञ्छे' । उकार इत् । ध्रस्नाति । उकारो धात्ववयव इत्येके । उध्रसांचकार । 'इष १५२६ आभीक्ष्ण्ये' । पौनःपुन्यं भृशार्थो वा आभीक्ष्ण्यम् । इष्णाति । 'तीषसह-' (सू२३४०) इत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषेर्ग्रहणं न तु इष्यतीष्णात्योरित्याहुः । एषिता । वस्तुतस्तु इष्णातेरपि इड्विकल्प उचितः । तथा च वार्तिकम्—'इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः' (वा ४४३५) इति । 'विष १५२७ विप्रयोगे' । विष्णाति । वेष्टा । 'प्रुष १५२८ प्लुष १५२९ स्नेहनसेवनपूरणेषु' । प्रुष्णाति । प्लुष्णाति । 'पुष १५३० पुष्टौ' । पोषिता । 'मुष १५३१ स्तेये' । मोषिता । 'खच १५३२ भूतप्रादुर्भावे' । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्नाति । वान्तोऽयमित्येके ।

२५६१। च्छ्वोः शूडनुनासिके च। ६। ४। १९। सतुक्कस्य छस्य वस्य च क्रमात् 'श' 'ऊठ्' एतावादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति। खौनाति। चखाव। खविता। शानचः परत्वादूठि कृते हलन्तत्वाभावान्न शानच्। खौनीहि। 'हेट १५३३ च'। ष्टुत्वम्। हेट्णाति। 'ग्रह १५३४ उपादाने'। स्वरितेत्। 'ग्रहिज्या–' (सू २४१२)। गृह्णाति–गृह्णीते।

२५६२। ग्रहोऽलिटि दीर्घः। ७। २। ३७। एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्न तु लिटि। ग्रहीता। लिटि तु जग्रहिथ। गृह्यात्। ग्रहीषीष्ट। 'ह्यन्त–' (सू २२९९) इति न वृद्धिः। अग्रहीष्टाम्। अग्रहीष्ट। अग्रहीषाताम्। अग्रहीषत।

इति तिङन्तक्र्यादिप्रकरणम्।

अथ तिङन्तचुरादिप्रकरणम्।

'चुर १५३५ स्तेये'।

२५६३। सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। ३। १। २५। एभ्यो णिच्स्यात्। चूर्णान्तेभ्यः 'प्रातिपदिकाद्धात्वर्थे–' (ग सू २०३) इत्येव सिद्धं तेषामिह ग्रहणं प्रपञ्चार्थम्। चुरादिभ्यस्तु स्वार्थे। 'पुगन्त–' (सू २१८९) इति गुणः। 'सनाद्यन्ताः–' (सू २३०४) इति धातुत्वम्। तिप्शबादि गुणायादेशौ। चोरयति।

२५६४। णिचश्च। १। ३। ७४। णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले। चोरयते। चोरयामास। चोरयिता। चोर्यात्। चोरयिषीष्ट। 'णिश्रि–' (सू २३१२) इति चङ्। 'णौ चङि–' (सू २३१४) इति ह्रस्वः। द्वित्वम्। 'हलादिः शेषः' (सू २१७९)। 'दीर्घो लघोः' (सू २३१८) इत्यभ्यासदीर्घः। अचूचुरत्–अचूचुरत। 'चिति १५३६ स्मृत्याम्'। चिन्तयति। अचिचिन्तत्। 'चिन्त' इति पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम्। तेन 'चिन्त्यात्' 'चिन्त्यते' इत्यादौ नलोपो न। चिन्तति। चिन्तेत्। एतच्च ज्ञापकं सामान्यापेक्षमित्येके। 'अत एकहल्–' (सू २२६०) इत्यत्र वृत्तिकृता 'जगाण' 'जगणतुः' इत्युदाहृतत्वात्। विशेषापेक्षमित्यपरे। अत एव 'आधृषाद्वा' (ग सू २०२) इत्यस्य न वैयर्थ्यम्। 'यत्रि १५३७ संकोचे'। यन्त्रयति। 'यन्त्र' इति पठितुं शक्यम्। यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम्। एवं कुद्रितन्त्रिमन्त्रिषु। 'स्फुडि १५३८ परिहासे'। स्फुण्डयति। इदित्करणात्स्फुण्डति। 'स्फुटि' इति पाठान्तरम्। स्फुण्टयति। 'लक्ष १५३९ दर्शनाङ्कनयोः'। 'कुद्रि १५४० अनृतभाषणे'। कुन्द्रयति। 'लड १५४१ उपसेवायाम्'। लाडयति। 'मिदि १५४२ स्नेहने'। मिन्दयति–मिन्दति। 'ओलडि १५४३ उत्क्षेपणे'। ओलण्डयति–ओलण्डति। ओकार इदित्येके। लण्डयति–लण्डति। उकारादिरयमित्यन्ये। उलण्डयति। 'जल १५४४ अपवारणे'। 'लज' इत्येके। 'पीड १५४५ अवगाहने'। पीडयति।

२५६५। भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्। ७। ४। ३। एषामुपधाया ह्रस्वो वा स्याच्चङ्परे णौ। अपीपिडत्–अपिपीडत्। 'नट १५४६ अवस्यन्दने'। अवस्यन्दनं नाट्यम्। 'श्रथ १५४७ प्रयत्ने'। 'प्रस्थाने' इत्येके। 'बध १५४८ संयमने'।

बाधयति। 'बन्ध' इति चान्द्रः। 'पृ १५४९ पूरणे'। पारयति। दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गं तद्धि सेट्कत्वाय। एवं पृणातिपिपर्तिभ्यां 'परिता' इत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम्। 'ऊर्ज १५५० बलप्राणनयोः'। 'पक्ष १५५१ परिग्रहे'। 'वर्ण १५५२ चूर्ण १५५३ प्रेरणे'। 'वर्ण वर्णने' इत्येके। 'प्रथ १५५४ प्रख्याने'। प्राथयति। 'नान्यो मितोऽहेतौ' इति वक्ष्यमाणत्वान्नास्य मित्त्वम्।

२५६६। अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्। ७।४।९५। एषामभ्यासस्याकारोऽन्तादेशः स्याच्चङ्परे णौ। इत्वापवादः। अपप्रथत्। 'पृथ १५५५ प्रक्षेपे'।

२५६७ उर्ऋत्। ७।४।७। उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ। इररारामपवादः। अपीपृथत्-अपपर्थत्। 'पथ' इत्येके। पाथयति। 'षम्ब १५५६ संबन्धने'। सम्बयति। अससम्बत्। 'शम्ब १५५७ च'। अशशम्बत्। 'साम्ब' इत्येके। 'भक्ष १५५८ अदने'। 'कुट्ट १५५९ छेदनभर्त्सनयोः'। 'पूरणे' इत्येके। कुट्टयति। पुट्ट १५६० चुट्ट १५६१ अल्पीभावे'। 'अट्ट १५६२ षुट्ट १५६३ अनादरे'। अट्टयति। अयं दोपधः। ष्टुत्वस्यासिद्धत्वात् 'न न्द्राः–' (सू २४४६) इति निषेधः। आट्टिटत्। 'लुण्ठ १५६४ स्तेये'। लुण्ठयति। 'लुण्टति' इति 'लुटि स्तेये' इति भौवादिकस्य। 'शठ १५६५ श्वठ १५६६ असंस्कारगत्योः'। 'श्वठि' इत्येके। 'तुजि १५६७ पिजि १५६८ हिंसाबलादाननिकेतनेषु'। तुञ्जयति। पिञ्जयति। इदित्करणात्तुञ्जति। पिञ्जति। 'तुज' 'पिज' इति केचित्। 'लजि' 'लुजि' इत्येके। 'पिस १५६९ गतौ'। पेसयति। 'पेसति' इति तु शपि गतम्। 'षान्त्व १५७० सामप्रयोगे'। श्वल्क १५७१ वल्क १५७२ परिभाषणे'। 'ष्णिह १५७३ स्नेहने'। 'स्फिट' इत्येके। 'स्मिट १४७४ अनादरे'। अषोपदेशत्वान्न षः। आसिस्मिटत्। 'ष्मिङ् अनादरे' इत्येके। ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ्। स्माययते। 'श्लिष १५७५ श्लेषणे'। 'पथि १५७६ गतौ'। पन्थयति-पन्थाति। 'पिच्छ १५७७ कुट्टने'। 'छदि १५७८ संवरणे'। छन्दयति-छन्दति। 'श्रण १५७९ दाने'। प्रायेणायं विपूर्वः। विश्राणयति। 'तड १५८० आघाते'। ताडयति। 'खड १५८१ खडि १५८२ कडि १५८३ भेदने'। खाडयति। खण्डयति। कण्डयति। 'कुडि १५८४ रक्षणे'। 'गुडि १५८५ वेष्टने'। 'रक्षणे' इत्येके। 'कुठि' इत्यन्ये। अवकुण्ठयति-अवकुण्ठति। 'गुठि' इत्यपरे। 'खुडि १५८६ खण्डने'। वटि १५८७ विभाजने। 'वडि' इत्येके। 'मडि १५८८ भूषायां हर्षे च'। 'भाडि १५८९ कल्याणे'। 'छर्द १५९० वमने'। 'पुस्त १५९१ बुस्त १५९२ आदरानादरयोः'। 'चुद १५९३ संचोदने'। 'नक्क १५९४ धक्क १५९५ नाशने'। णोपदेशलक्षणे पर्युदस्तोऽयम्। प्रनक्कयति। 'चक्क १५९६ चुक्क १५९७ व्यथने'। 'क्षल १५९८ शौचकर्मणि'। 'तल १५९९ प्रतिष्ठायाम्'। 'तुल १६०० उन्माने'। तोलयति। अतूतुलत्। कथं 'तुलयति तुलना' इत्यादि। '–अतुलोपमाभ्याम्–' (सू ६३०) इति निपातनादकन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच्। 'दुल १६०१ उत्क्षेपे'। 'पुल १६०२ महत्त्वे'। 'चुल १६०३ समुच्छ्राये'। 'मूल १६०४ रोहणे'। 'कल १६०५ बिल १६०६ क्षेपे'। 'बिल १६०७ भेदने' 'तिल १६०८ स्नेहने'। 'चल १६०९ भृतौ'। 'पाल १६१० रक्षणे'। 'लूष १६११ हिंसायाम्'। 'शुल्क १६१२ माने'। 'शूर्प १६१३ च'। 'चुट १६१४ छेदने'। 'मुट १६१५ संचूर्णने'। 'पडि १६१६ पसि १६१७ नाशने'। पण्डयति-पण्डति। पंसयति-पंसति। 'व्रज १६१८ मार्ग-

संस्कारगत्योः'। 'शुल्क १६१९ अतिस्पर्शने'। 'चपि १६२० गत्याम्'। चम्पयति-चम्पति। 'क्षपि १६२१ क्षान्त्याम्'। क्षम्पयति-क्षम्पति। 'छजि १६२२ कृच्छ्रजीवने'। 'श्वर्त १६२३ गत्याम्'। 'श्वभ्र १६२४ च'। 'ज्ञप १६२५ मिच्च'। अयं ज्ञाने ज्ञापने च वर्तते।

२५६८। मितां ह्रस्वः। ६।४।९२। मितामुपधाया ह्रस्वः स्याण्णौ परे। ज्ञपयति। 'यम १६२६ च परिवेषणे'। चान्मित्। परिवेषणमिह वेष्टनम्। न तु भोजना नापि वेष्टना। यमयति चन्द्रम्। परिवेष्टत इत्यर्थः। 'चह १६२७ परिकल्पने'। चहयति। अचीचहत्। कथादौ वक्ष्यमाणस्य तु अदन्तत्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न। अचचहत्। 'चप' इत्येके। चपयति। 'रह १६२८ त्यागे' इत्येके। अरीरहत्। कथादेस्तु अररहत्। 'बल १६२९ प्राणने'। वलयति। 'चिञ् १६३० चयने'।

२५६९। चिस्फुरोर्णौ। ६।१।५४। आत्त्वं वा स्यात्।

२५७०। अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ। ७।३।३६। चपयति-चययति। ञित्करणसामर्थ्यादस्य णिज्विकल्पः। चयते। प्रणिचयति-प्रनिचयति। 'नान्ये मितोऽहेतौ' (ग सू १९८)। अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः। तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न। 'घट्ट १६३१ चलने'। 'मुस्त १६३२ संघाते'। 'खट्ट १६३३ संवरणे'। 'षट्ट १६३४ स्फिट्ट १६३५ चुबि १६३६ हिंसायाम्'। 'पुल १६३७ संघाते'। 'पूर्ण' इत्येके। 'पुण' इत्यन्ये। 'पुंस १६३८ अभिवर्धने'। 'टकि १६३९ बन्धने'। टङ्कयति-टङ्कति। 'धूस १६४० कान्तिकरणे'। धूसयति। दन्त्यान्तः। 'मूर्धन्यान्तः' इत्येके। 'तालव्यान्तः' इत्यपरे। 'कीट १६४१ वर्णे'। 'चूर्ण १६४२ संकोचने'। 'पूज १६४३ पूजायाम्'। 'अर्क १६४४ स्तवने'। 'तपने' इत्येके। 'शुठ १६४५ आलस्ये'। 'शुठि १६४६ शोषणे'। शुण्ठयति-शुण्ठति। 'जुड १६४७ प्रेरणे'। 'गज १६४८ मार्ज १६४९ शब्दार्थौ'। गाजयति। मार्जयति। 'मर्च १६५० च'। मर्चयति। 'घृ १६५१ प्रस्रवणे'। 'स्रावणे' इत्येके। 'पचि १६५२ विस्तारवचने'। पञ्चयति। 'पञ्चते' इति व्यक्तार्थस्य शपि गतम्। 'तिज १६५३ निशाने'। तेजयति। 'कृत १६५४ संशब्दने'।

२५७१। उपधायाश्च। ७।१।१०१। धातोरुपधाभूतस्य ऋत इत्स्यात्। रपरत्वम्। 'उपधायां च' (सू २२६९) इति दीर्घः। कीर्तयति। 'उर्ऋत्' (सू २५६७)। अचीकृतत्-अचिकीर्तत्। 'वर्ध १६५५ छेदनपूरणयोः'। 'कुबि १६५६ आच्छादने'। कुम्बयति। 'कुभि' इत्येके। 'लुबि १६५७ तुबि १६५८ अदर्शने'। 'अर्दने' इत्येके। 'ह्लप १६५९ व्यक्तायां वाचि'। 'क्लृप' इत्येके। 'चुटि १६६० छेदने'। 'इल १६६१ प्रेरणे'। एलयति। ऐलिलत्। 'म्रक्ष १६६२ म्लेच्छने'। 'म्लेछ १६६३ अव्यक्तायां वाचि'। 'ब्रूस १६६४ बर्ह १६६५ हिंसायाम्'। केचिदिह 'गर्ज गर्द शब्दे' 'गर्ध अभिकाङ्क्षायाम्' इति पठन्ति। 'गुर्द १६६६ पूर्वनिकेतने'। 'जसि १६६७ रक्षणे'। 'मोक्षणे' इति केचित्। जंसयति-जंसति। 'ईड १६६८ स्तुतौ'। 'जसु १६६९ हिंसायाम्'। 'पिडि १६७० संघाते'। 'रुष १६७१ रोषे'। 'रुट' इत्येके। 'डिप १६७२ क्षेपे'। 'ष्टुप १६७३ समुच्छ्राये'।

आ कुस्मादात्मनेपदिनः। 'कुस्मनाम्नो वा' इति वक्ष्यते तमभिव्याप्येत्यर्थः। अकर्तृगामिफलार्थमिदम्। 'चित १६७४ संचेतने'। चेतयते। अचीचित। 'दशि १६७५ दंशने'।

दंशयते । अददंशत । इदित्त्वाण्णिजभावे । दंशाति । आकुस्मीयमात्मनेपदं णिच्संनियोगेनैवेति व्याख्यातारः । नलोपे सञ्जिसाहचर्याद्भ्वादेरेव ग्रहणम् । 'दसि १६७६ दर्शनदंशनयोः' । दंसयते-दंसति । 'दस' इत्यप्येके । 'डप १६७७ डिप १६७८ संघाते' । 'तन्त्रि १६७९ कुटुम्बधारणे' । तन्त्रयते । चान्द्रा धातुद्वयमिति मत्त्वा 'कुटुम्बयते' इत्युदाहरन्ति । 'मन्त्रि १६८० गुप्तपरिभाषणे' । 'स्पश १६८१ ग्रहणसंश्लेषणयोः' । 'तर्ज १६८२ भर्त्स १६८३ तर्जने' । बस्त १६८४ गन्ध १६८५ अर्दने' । बस्तयते । गन्धयते । 'विष्क १६८६ हिंसायाम्' । हिष्क' इत्येके । 'निष्क १६८७ परिमाणे' । 'लल १६८८ ईप्सायाम्' । 'कूण १६८९ सं कोचे' । 'तूण १६९० पूरणे' । 'भ्रूण १६९१ आशाविशङ्कयोः' । 'शठ १६९२ श्लाघायम्' । यक्ष १६९३ पूजायाम्' । 'स्यम १६९४ वितर्के' । 'गूर १६९५ उद्यमने' । 'शम १६९६ लक्ष १६९७ आलोचने' । 'नान्ये मितः-' इति मित्त्वनिषेधः । शामयते । 'कुत्स १६९८ अवक्षेपणे' । 'त्रुट १६९९ छेदने' । 'कुट' इत्येके । 'गल १७०० स्रवणे' । 'भल १७०१ आभण्डने' । 'कूट १७०२ आप्रदाने' । 'अवसादने' इत्येके । 'कुट्ट १७०३ प्रतापने' । 'वञ्चु १७०४ प्रलम्भने' । 'वृष १७०५ शक्तिबन्धने' । शक्तिबन्धनं प्रजननसामर्थ्यं शक्तिसंबन्धश्च । वर्षयते । 'मद १७०६ तृप्तियोगे' । मदयते । 'दिवु १७०७ परिकूजने' । 'गृ १७०८ विज्ञाने' । गारयते । 'विद १७०९ चेतनाख्याननिवासेषु' । वेदयते ।

> सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।
> विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ॥

'मान १७१० स्तम्भे' । मानयते । 'यु १७११ जुगुप्सायाम्' । यावयते । 'कुस्म १७१२ नाम्ने वा' (ग सू १९९) 'कुस्म' इति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथ वा 'कुस्म' इति प्रातिपदिकम् । ततो धात्वर्थे णिच् । इत्याकुस्मीयाः ।

'चर्च १७१३ अध्ययने' । 'बुक्क १७१४ भाषणे' । 'शब्द १७१५ उपसर्गादाविष्कारे च' । चाद्भाषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः । 'अनुपसर्गाच्च' । 'आविष्कारे' इत्येव । शब्दयति । 'कण १७१६ निमीलने' । काणयति । 'णौ चङ्युपधाया ह्रस्वः' (सू ३३२४) । काण्यादीनां वा' (वा ४६१३) इति विकल्प्यते । अचीकणत्-अचकाणत् । 'जभि १७१७ नाशने' । जम्भयति-जम्भति । 'षूद १७१८ क्षरणे' । सूदयति । असूषुदत् । 'जसु १७१९ ताडने' । जासयति-जसति । 'पश १७२० बन्धने' । पाशयति । 'अम १७२१ रोगे' । आमयति । 'नान्ये मितः-' इति निषेधः । 'अम' गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ 'न कम्यमिचमाम्' इति निषेधः । आमयति । 'चट १७२२ स्फुट १७२३ भेदने' । विकासे शशपोः 'स्फुटति-स्फोटते' इत्युक्तम् । 'घट १७२४ संघाते' । घाटयति । 'हन्त्यर्थाश्च' (ग सू २००) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्त इत्यर्थः । 'दिवु १७२५ मर्दने' । उदित्त्वाद्देवतीत्यपि । 'अर्ज १७२६ प्रतियत्ने । अयमर्थान्तरेऽपि । द्रव्यमर्जयति । घुषिर् १७२७ विशब्दने' । घोषयति । 'घुषिरविशब्दने' (सू ३०६३) इति सूत्रे 'अविशब्दने' इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्त्वादङ्वा । अघुषत्-अघोषीत् । ण्यन्तस्य तु अजूघुषत् । 'आङः क्रन्द १७२८ सातत्ये' । भौवादिकः क्रन्दधातुराह्वानाद्यर्थ उक्तः । स एवाङ्पूर्वो णिचं लभते सातत्ये । आक्रन्दयति । अन्ये तु 'आङ्पूर्वो घुषिः क्रन्द-

सातत्ये' इत्याहुः। आघोषयति। 'लस १७२९ शिल्पयोगे'। 'तसि १७३० भूष १७३१ अलंकरणे'। अवतंसयति-अवतंसति। भूषयति। 'अर्ह १७३२ पूजायाम्'। 'ज्ञा १७३३ नियोगे'। आज्ञापयति। 'भज १७३४ विश्राणने'। 'शृधु १७३५ प्रसहने'। भशशर्धत्-अशीशृधत्'। 'यत १७३६ निकारोपस्कारयोः'। 'रक १७३७ लग १७३८ आस्वादने'। रघ' इत्येके। 'रग' इत्यन्ये। 'अञ्चु १७३९ विशेषणे'। अञ्चयति। उदित्त्वमिड्विकल्पार्थम्। अत एव विभाषितो णिच्। अञ्चति। एवं शृधुजसुप्रभृतीनामपि बोध्यम्। 'लिगि १७४० चित्रीकरणे'। लिङ्गयति-लिङ्गति। 'मुद १७४१ संसर्गे'। मोदयति सक्तून्घृतेन। 'त्रस १७४२ धारणे'। 'ग्रहणे' इत्येके। 'वारणे' इत्यन्ये। 'उध्रस १७४३ उञ्छे'। उकारो धात्ववयव इत्येके। नेत्यन्ये। ध्रासयति। उध्रासयति। 'मुच १७४४ प्रमोचने मोदने च'। 'वस १७४५ स्नेहच्छेदापहरणेषु'। 'चर १७४६ संशये'। 'च्यु १७४७ सहने'। 'हसने च' इत्येके। च्यावयति। 'च्युस' इत्येके। च्योसयति। 'भुवोऽवकल्कने १७४८'। अवकल्कनं मिश्रीकरणमित्येके। चिन्तनमित्यन्ये। भावयति। 'कृपेश्च १७४९'। कल्पयति।

'आ स्वदः सकर्मकात्' (ग सू २०१)। स्वदिमभिव्याप्य संभवत्कर्मभ्य एव णिच्। 'ग्रस १७५० ग्रहणे'। ग्रासयति फलम्। 'पुष १७५१ धारणे'। पोषयत्याभरणम्। 'दल १७५२ विदारणे'। दालयति। 'पट १७५३ पुट १७५४ लुट १७५५ तुजि १७५६ मिजि १७५७ पिजि १७५८ लुजि १७५९ भाजि १७६० लघि १७६१ त्रसि १७६२ पिसि १७६३ कुसि १७६४ दशि १७६५ कुशि १७६६ घट १७६७ घटि १७६८ बृहि १७६९ बर्ह १७७० बल्ह १७७१ गुप १७७२ धूप १७७३ विच्छ १७७४ चीव १७७५ पुथ १७७६ लोकृ १७७७ लोचृ १७७८ णद १७७९ कुप १७८० तर्क १७८१ वृतु १७८२ वृधु १७८३ भाषार्थाः'। पाटयति। पोटयति। लोटयति। तुञ्जयति। तुञ्जति। एवं परेषाम्। घाटयति। घण्टयति।

२५७२। नाग्लोपिशास्वृदिताम्। ७। ४। २। णिच्यग्लोपिनः शास्तेॠदितां चोपधाया ह्रस्वो न स्याच्चङ्परे णौ। अलुलोकत्। अलुलोचत्। वर्तयति। वर्धयति। उदित्त्वाद्वर्तति। वर्धति। 'रुट १७८४ लजि १७८५ अजि १७८६ दसि १७८७ भृशि १७८८ रुशि १७८९ शीक १७९० रुसि १७९१ नट १७९२ पुटि १७९३ जि १७९४ चि १७९५ रघि १७९६ लघि १७९७ अहि १७९८ रहि १७९९ महि १८०० च'। 'लडि १८०१ तड १८०२ नल १८०३ च'। 'पूरी १८०४ आप्यायने'। ईदित्त्वं निष्ठायामिण्निषेधाय। अत एव णिज्वा। पूरयति-पूरति। 'रुज १८०५ हिंसायाम्'। 'ष्वद १८०६ आस्वादने'। 'स्वाद' इत्येके। असिष्वदत्। दीर्घस्य त्वषोपदेशत्वात्। असिस्वदत्।

'आ धृषाद्वा' (ग सू २०२)। इत ऊर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य। 'युज १८०७ पृच १८०८ संयमने'। योजयति-योजति। अयौक्षीत्। पर्चयति-पर्चति। पर्चिता। अपर्चीत्। 'अर्च १८०९ पूजायाम्'। 'षह १८१० मर्षणे'। साहयति। 'स एवायं नागः सहति कलभेभ्यः परिभवम्'। 'ईर १८११ क्षेपे'। 'ली १८१२ द्रवीकरणे'। लाययति-लयति। लेता। 'वृजी १८१३ वर्जने'। वर्जयति-वर्जति। 'वृञ् १८१४ आवरणे'। वारयति-वरति-वरते। वरिता-वरीता। 'जॄ १८१५ वयोहानौ'। जारयति-जरति। जरिता-जरीता।

'ज्रि १८१६ च' । ज्राययति–ज्रयति । ज्रेता । 'रिच १८१७ वियोजनसंपर्चनयोः' । रेचयति–रेचति । रेक्ता । 'शिष १८१८असर्वोपयोगे' । शेषयति–शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये । 'तप १८१९ दाहे' । तापयति–तपति । तप्ता । 'तृप १८२० तृप्तौ' । 'संदीपने' इत्येके । तर्पयति–तर्पति । तर्पिता । 'छृदी १८२१ संदीपने' । छर्दयति–छर्दति । छर्दिता । छर्दिष्यति । 'सेऽसिचि–(सू २५०६) इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । 'चृप छृप दृप संदीपने' इत्येके । चर्पयति । छर्पयति । 'दृभी १८२२ भये' । दर्भयति–दर्भति । दर्भिता । 'दृभ १८२३ संदर्भे' । अयं तुदादावीदित् । 'श्रथ १८२४ मोक्षणे' । 'हिंसायाम्' इत्येके । 'मी १८२५ गतौ' । माययति–मयति । मेता । 'ग्रन्थ १८२६ बन्धने' । ग्रन्थयति–ग्रन्थति । 'शीक १८२७ आमर्षणे' । 'चीक १८२८ च' । 'अर्द १८२९ हिंसायाम्' । स्वरितेत् । अर्दयति–अर्दति–अर्दते । 'हिसि १८३० हिंसायाम्' । हिंसयति–हिंसति । 'हिनस्ति' इति श्नमि गतम् । 'अर्ह १८३१ पूजायाम्' । 'आङः षद १८३२ पद्यर्थे' । आसादयति–आसीदति । 'पाघ्रा–' (सू २३६०) इति सीदादेशः । आसत्ता । आसात्सीत् । 'शुन्ध १८३३ शौचकर्मणि' । शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् । 'छद १८३४ अपवारणे' । स्वरितेत् । 'जुष १८३५ परितर्कणे' । परितर्कणमूहो हिंसा वा । 'परितर्पणे' इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति–जोषति । प्रीतिसेवनयोर्जुषत इति तुदादौ । 'धूञ् १८३६ कम्पने' । णावित्यधिकृत्य । 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा ४५१९) । धूनयति–धवति–धवते । केचित्तु 'धूञ्प्रीणोः–' इति पठित्वा प्रीणातिसाहचर्याद्धुनोतेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च । स्वादौ ह्रस्वश्च । तथा च कविरहस्ये—

> 'धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम् ।
> वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ॥'.

'प्रीञ् १८३७ तर्पणे' । प्रीणयति । 'धूञ्प्रीणोः–' इति हरदत्तोक्तपाठे तु प्राययति–प्रयति–प्रयते । 'श्रन्थ १८३८ ग्रन्थ १८३९ संदर्भे' । 'आप्लृ १८४० लम्भने' । आपयति–आपति । आपत् । आप्ता । स्वरितेदयमित्येके । आपते । 'तनु १८४१ श्रद्धोपकरणयोः' । 'उपसर्गाच्च दैर्घ्ये' । तानयति । वितानयति–तनति । वितनति । 'चन श्रद्धोपहननयोः' इत्येके । चानयति–चनति । 'वद १८४२ संदेशवचने' । वादयति । स्वरितेत् । वदति–वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् । 'वच १८४३ परिभाषणे' । वाचयति–वचति । वक्ता । अवाक्षीत् । 'मान १८४४ पूजायाम्' । मानयति–मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे तु 'मानयते' (इत्याकुस्मीयः ।) 'मन्यते' इति दिवादौ । 'मनुते' इति तनादौ च । 'भू १८४५ प्राप्तावात्मनेपदी' । भावयते–भवते । णिच्संनियोगेनैवात्मनेपदमित्येके । भवति । 'गर्ह १८४६ विनिन्दने' । 'मार्ग १८४७ अन्वेषणे' । 'कठि १८४८ शोके' । उत्पूर्वोऽयमुत्कण्ठायाम् । 'कण्ठते' इत्यात्मनेपदी गतः । 'मृजू १८४९ शौचालंकारयोः' । मार्जयति–मार्जति । मार्जिता–मार्ष्टा । 'मृष १८५० तितिक्षायाम्' । स्वरितेत् । मर्षयति–मर्षति–मर्षते । मृष्यति–मृष्यत इति दिवादौ । सेचने शपि मर्षति । 'धृष १८५१ प्रसहने' । धर्षयति–धर्षति । इत्याकुस्मीयाः ।

अथादन्ताः। 'कथ १८५२ वाक्यप्रबन्धे'। अल्लोपस्य स्थानिवद्भावान्न वृद्धिः। कथयति। अग्लोपित्वान्न दीर्घसन्वद्भावौ। अचकथत्। 'वर १८५३ ईप्सायाम्'। वरयति। वारयतीति गतम्। 'गण १८५४ संख्याने'। गणयति।

२५७३। ई च गणः। ७।४।९७। गणेरभ्यासस्य ईत्स्याच्चङ्परे णौ। चादत्। अजगणत्-अजीगणत्। 'शठ १८५५ श्वठ १८५६ सम्यगवभाषणे'। 'पट १८५७ वट १८५८ ग्रन्थे'। 'रह १८५९ त्यागे'। अररहत्। 'स्तन १८६० गदी १८६१ देवशब्दे'। स्तनयति। गदयति। अजगदत्। 'पत १८६२ गतौ वा'। वा णिजन्तः। वादन्त इत्येके। आद्ये पतयति-पतति। पतांचकार। अपतीत्। द्वितीये पातयति। अपीपतत्। 'पष १८६३ अनुपसर्गात्' गतावित्येव। पषयति। 'स्वर १८६४ आक्षेपे'। स्वरयति। 'रच १८६५ प्रतियत्ने'। रचयति। 'कल १८६६ गतौ संख्याने च'। 'चह १८६७ परिकल्कने'। परिकल्कनं दम्भः शाठ्यं च। 'मह १८६८ पूजायाम्'। महयति। महतीति शपि गतम्। 'सार १८६९ कृप १८७० श्रथ १८७१ दौर्बल्ये'। सारयति। कृपयति। श्रथयति। 'स्पृह १८७२ ईप्सायाम्'। 'भाम १८७३ क्रोधे'। अबभामत्। 'सूच १८७४ पैशून्ये'। सूचयति। अषोपदेशत्वान्न षः। असूसुचत्। 'खेट १८७५ भक्षणे'। तृतीयान्त इत्येके। 'खोट' इत्यन्ये। 'क्षोट १८७६ क्षेपे'। 'गोम १८७७ उपलेपने'। अजुगोमत्। 'कुमार १८७८ क्रीडायाम्'। अचुकुमारत्। 'शील १८७९ उपधारणे'। उपधारणमभ्यासः। 'साम १८८० सान्त्वप्रयोगे'। अससामत्। 'साम सान्त्वने' इत्यतीतस्य तु असीषमत्। 'वेल १८८१ कालोपदेशे'। वेलयति। 'काल' इति पृथग्धातुरित्येके। कालयति। 'पल्यूल १८८२ लवनपवनयोः'। 'वात १८८३ सुखसेवनयोः'। 'गतिसुखसेवनेषु' इत्येके। वातयति। अववातत्। 'गवेष १८८४ मार्गणे'। अजगवेषत्। 'वास १८८५ उपसेवायाम्'। 'निवास १८८६ आच्छादने'। अनिनिवासत्। 'भाज १८८७ पृथक्कर्मणि'। 'सभाज १८८८ प्रीतिदर्शनयोः'। प्रीतिसेवनयोः' इत्यन्ये। सभाजयति। 'ऊन १८८९ परिहाणे'। ऊनयति। 'ओः पुयण्ज्-' (सू २५७७) इति सूत्रे 'पयोः' इति वक्तव्ये वर्गप्रत्याहारजकारग्रहो लिङ्गं 'णिचि अच आदेशो न स्याद्द्वित्वे कार्ये' इति। 'यत्र द्विरुक्तावभ्यासोत्तरखण्डस्यायोऽच्प्रक्रियायां परिनिष्ठिते रूपे वावर्णो लभ्यते, तत्रैवायं निषेधः'। ज्ञापकस्य सजातीयापेक्षत्वात्। तेन 'अविकीर्तत्' इति सिद्धम्। प्रकृते तु 'न'शब्दस्य द्वित्वं तत उत्तरखण्डेऽल्लोपः। औननत्। माभवानूननत्। 'ध्वन १८९० शब्दे'। अदध्वनत्। 'कूट १८९१ परितापे'। 'परिदाहे' इत्यन्ये। 'संकेत १८९२ ग्राम १८९३ कुण १८९४ गुण १८९५ चामन्त्रणे'। चात्कूटोऽपि। कूटयति। संकेतयति। ग्रामयति। कुणयति। गुणयति। पाठान्तरम्। 'केत १८९६ श्रावणे निमन्त्रणे च'। केतयति। निकेतयति। 'कुण गुण चामन्त्रणे'। चकारात्केतने। 'कूण १८९७ संकोचनेऽपि'। 'स्तेन १८९८ चौर्ये'। अतिस्तेनत्।

आ गर्वादात्मनेपदिनः। 'पद १८९९ गतौ'। पदयते। अपपदत। 'गृह १९०० ग्रहणे' गृहयते। 'मृग १९०१ अन्वेषणे'। मृगयते। 'मृग्यति' इति कण्ड्वादिः। 'कुह १९०२ विस्मापने'। 'शूर १९०३ वीर १९०४ विक्रान्तौ'। 'स्थूल १९०५ परिबृंहणे'। स्थूलयते। अतुस्थूलत। 'अर्थ १९०६ उपयाच्ञायाम्'। अर्थयते। आर्तथत। 'सत्र १९०७ संतान-

क्रियायाम्' । असस्त्रत् । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते । 'गर्व १९०८ माने' । गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । 'धातोरन्त उदात्तः' लिटि 'आम्' च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ।

'सूत्र १९०९ वेष्टने' । सूत्रयति । असुसूत्रत् । 'मूत्र १९१० प्रस्रवणे' । मूत्रयति–मूत्रति । 'रूक्ष १९११ पारुष्ये' । 'पार १९१२ तीर १९१३ कर्मसमाप्तौ' । अपपारत् । अतितीरत् । 'पुट १९१४ संसर्गे' । पुटयति । 'धेक १९१५ दर्शने' इत्येके । अदिधेकत् । 'कत्र १९१६ शैथिल्ये' । कत्रयति–कत्रति । 'कर्त' इत्यप्येके । कर्तयति–कर्तति । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (ग सू २०३) । प्रातिपदिकाद्धात्वर्थे णिच्स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । 'णौ चङि–' (सू २३१४) इत्यत्र भाष्ये तु 'वृद्धेर्लोपो बलीयान्' इति स्थितम् । अपपटत् । 'तत्करोति तदाचष्टे'[1] (ग सू २०४) । पूर्वस्य प्रपञ्चः । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः । लडर्थस्त्वविवक्षितः । 'तेनातिक्रामति' (ग सू २०५) । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति । 'धातुरूपं च' (ग सू २०६) । णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते । चशब्दोऽनुक्तसमुच्चयार्थः । 'तथा च वार्तिकम्—'आख्यानात्कृतस्तदाचष्टे इति णिच्कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्' (वा १७६६) इति । कंसवधमाचष्टे कंसं घातयति । इह 'कंसं हन्' इति स्थिते ।

२५७५ । हनस्तोऽचिण्णलोः । ७ । ३ । ३२ । हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाड्द्वित्वयोर्दोषः । किंच । कुत्वतत्वे न स्यातां । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । 'प्रकृतिवच्च' इति चकारो भिन्नक्रमः । कारकं च । चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । 'कर्तृकरणाद्धात्वर्थे' । (ग सू २०७) । कर्तुर्व्यापारार्थं यत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति । असयति । 'वल्क १९१७ दर्शने' । 'चित्र १९१८ चित्रीकरणे' । 'आलेख्यकरणे' इत्यर्थः । कदाचिद्दर्शने । 'चित्र' इत्ययमद्भुतदर्शने णिचं लभते । चित्रयति । 'अंस १९१९ समाघाते' । 'वट १९२० विभाजने' । 'लज १९२१ प्रकाशने' । 'वटि' 'लजि' इत्येके । वण्टयति । लञ्जयति । अदन्तेषु पाठबलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञ्जापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते 'कथापयति' 'गणापयति' इत्यादि । 'मिश्र १९२२ संपर्के' । 'संग्राम १९२३ युद्धे' । अयमनुदात्तेत् । अकारप्रश्लेषात् । अससंग्रामत । 'स्तोम १९२४ श्लाघायाम्' । अतुस्तोमत् । 'छिद्र १९२५ कर्णभेदने' । 'करणभेदने' इत्यन्ये । 'कर्ण' इति धात्वन्तरमित्यन्ये । 'अन्ध १९२६ दृष्ट्युपघाते' । 'उपसंहारे' इत्यन्ये । आन्दधत् । 'दण्ड १९२७ दण्डनिपातने' । 'अङ्क १९२८ पदे लक्षणे च' । आञ्चकत् । 'अङ्ग १९२९ च' । आञ्जगत् । 'सुख १९३० दुःख १९३१ तत्क्रियायाम्' । 'रस १९३२ आस्वादनस्नेहनयोः' । 'व्यय १९३३ वित्तसमुत्सर्गे' । अवव्ययत् । 'रूप १९३४ रूपक्रियायाम्' । रूपस्य दर्शनं करणं वा रूपक्रिया । 'छेद १९३५

१ 'तत्करोति' इत्यंशस्तु वार्तिके (१७६६) सिद्ध एव गणसूत्रे लिखितः ।

द्वैधीकरणे'। अचिच्छेदत्। 'छद १९३६ अपवारणे' इत्येके। छदयति। 'लाभ १९३७ प्रेरणे'। 'व्रण १९३८ गात्रविचूर्णने'। 'वर्ण १९३९ वर्णक्रियाविस्तारगुणवचनेषु'। वर्णक्रिया वर्णकरणम्। सुवर्णं वर्णयति। कथां वर्णयति। विस्तृणातीत्यर्थः। हरिं वर्णयति। स्तौतीत्यर्थः। 'बहुलमेतन्निदर्शनम्' (ग सू २०८)। अदन्तधातुनिदर्शनमित्यर्थः। बाहुलकादन्येऽपि बोध्याः। तद्यथा। 'पर्ण १९४० हरितभावे'। अपपर्णत्। 'विष्क १९४१ दर्शने'। 'क्षप १९४२ प्रेरणे'। 'वस १९४३ निवासे'। 'तुत्थ १९४४ आवरणे'। एवमान्दोलयति। प्रेङ्खोलयति। विडम्बयति। अवधीरयतीत्यादि। अन्ये तु दशगणीपाठो 'बहुलम्' इत्याहुः। तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः। अपरे तु नवगणीपाठो 'बहुलम्' इत्याहुः। तेनापठितेभ्योऽपि क्वचित्स्वार्थे णिच्। 'रामो राज्यमचीकरत्' इति यथेत्याहुः। चुरादिश्च एव बहुलं णिजित्यर्थ इत्यन्ये। सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः। 'णिङङ्गान्निरसने' (ग सू २०९)। अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात्। हस्तौ निरस्यति हस्तयते। पादयते। 'श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च' (ग सू २१०)। श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते णिङ् च धात्वर्थे। श्वेताश्वमाचष्टे तेनातिक्रामति वा श्वेतयते। अश्वतरमाचष्टेऽश्वयते। गालोडितं वाचां विमर्शः। तत्करोति गालोडयते। आह्वरयते। केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि। 'पुच्छादिषु धात्वर्थे इत्येव सिद्धम्' (ग सू २११)। णिजन्तादेव बहुलवचनादात्मनेपदमस्तु। मास्तु 'पुच्छभाण्ड–' (सू २६७६) इति णिङ्विधिः। सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः।

इति तिङन्तचुरादिप्रकरणम्।

अथ तिङन्तणिच्प्रकरणम्।

२५७५। तत्प्रयोजको हेतुश्च। १। ४। ५५। कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात्।

२५७६। हेतुमति च। ३। १। २६। प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्स्यात्। भवन्तं प्रेरयति भावयति। 'णिचश्च' (सू २५६४) इति कर्तृगे फल आत्मनेपदम्। भावयते। भावयांबभूव।

२५७७। ओः पुयण्ज्यपरे। ७। ४। ८०। सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः। अबीभवत्। अपीपवत्। मूङ्। अमीमवत्। अयीयवत्। अरीरवत्। अलीलवत्। अजीजवत्।

२५७८। स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा। ७। ४। ८१। एषामभ्यासोकारस्य इत्त्वं वा स्यात्सन्यवर्णपरे धात्वक्षरे परे। असिस्रवत्–असुस्रवत्। 'नाग्लोपि–' (सू २५७२) इति ह्रस्वनिषेधः। अशशासत्। अडुढौकत्। अचीचकासत्। मतान्तरे अचचकासत्। 'अग्लोपि' इति सुब्धातुप्रकरणे उदाहरिष्यते। ण्यन्ताण्णिच्। पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः। चोरयति। 'णौ चङि–' (सू २३१५) इति ह्रस्वः। 'दीर्घो लघोः' (सू २३१८)। न चाग्लोपित्वाद्द्वयोरप्यसंभवः। ण्याकृतिनिर्देशात्। अचूचुरत्।

२५७९। णौ च संश्चङोः। ६। १। ३१। सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं

त्रा स्यात्। 'संप्रसारणं तदाश्रयं च कार्यं बलवत्' (प १२९) इति वचनात्संप्रसारणम्। पूर्वरूपम्। अशूशवत्। अलघुत्वान्न दीर्घः। अशिश्वयत्।

२५८०। स्तम्भुसिवुसहां चङि। ८। ३। ११६। उपसर्गनिमित्त एषां सस्य षो न स्याच्चङि। अवातस्तम्भत्। पर्यसीषिवत्। न्यसीषहत्। आटिटत्। आशिशत्। बहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात्प्रागेव। ओणेरृदित्करणाल्लिङ्गात्। मा भवानीदिधत्। एजादावेधतौ विधानान्न वृद्धिः। मा भवान्प्रेदिधत्। 'नन्द्राः-' (सू २४४६) इति नदराणां न द्वित्वम्। औन्दिदत्। आड्डिडत्। आर्चिचत्। 'उब्ज' आर्जवे। उपदेशे दकारोपधः। 'भुजन्युब्जौ पाण्युपतापयोः' (सू२८७७) इति सूत्रे निपातनाद्दस्य बः स चान्तरङ्गोऽपि द्वित्वविषये 'नन्द्राः-' (सू२४४६) इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक्। दकारोच्चारणसामर्थ्यात्। औब्जिजत्। अजादेरित्येव। नेह। अदिद्रयत्।

२५८१। रभेरशब्लिटोः। ७। १। ६३। रभेर्नुम्स्यादचि न तु शब्लिटोः। अररम्भत्। भे

२५८२। लभेश्च। ७। १। ६४। अललम्भत्। 'हेरचङि' (सू २५३१) इति सूत्रे 'अचङि' इत्युक्तेः कुत्वं न। अजीहयत्। 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' (सू २५६६)। असस्मरत्। अददरत्। तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः।

२५८३। विभाषा वेष्टिचेष्ट्योः। ७। ४। ९६। अभ्यासस्यात्त्वं वा स्याच्चङ्परे णौ। अववेष्टत्-अविवेष्टत्। अचचेष्टत्-अचिचेष्टत्। 'भ्राजभास-' (सू २५६९) इत्यादिना वोपधाह्रस्वः। अबिभ्रजत्-अबभ्राजत्। 'काण्यादीनां चेति वक्तव्यम्' (वा ४६१३)। ण्यन्ताः कणरणभणश्रणलुपहेठः काण्यादयः षड्भाष्य उक्ताः। ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिका न्यासे। 'चाणिलोठी' इत्यप्यन्यत्र इत्थं द्वादश। अचीकणत्-अचकाणत्।

२५८४। स्वापेश्चङि। ६। १। १८। ण्यन्तस्य स्वपेश्चङि संप्रसारणं स्यात्। असूषुपत्।

२५८५। शाच्छासाह्वाव्यावेपां युक्। ७। ३। ३७। णौ। पुकोऽपवादः। शाययति। ह्वाययति।

२५८६। ह्वः संप्रसारणम्। ६। १। ३२। सन्परे चङ्परे च णौ ह्वः संप्रसारणं स्यात्। अजूहवत्-अजुहावत्।

२५८७। लोपः पिबतेरीच्चाभ्यासस्य। ७। ४। ४। पिबतेरुपधाया लोपः स्यादभ्यासस्य ईदन्तादेशश्च चङ्परे णौ। अपीप्यत्। 'अर्तिह्री-' (सू २५७०) इति पुक्। अर्पयति। ह्रेपयति। व्लेपयति। रेपयति। यलोपः। क्नोपयति। क्ष्मापयति। स्थापयति।

२५८८। तिष्ठतेरित्। ७। ४। ५। उपधाया इदादेशः स्याच्चङ्परे णौ। अतिष्ठिपत्।

२५८९। जिघ्रतेर्वा। ७। ४। ६। अजिघ्रिपत्-अजिघ्रपत्। 'उर्ऋत्' (सू २५६७)। अचीकृतत्-अचिकीर्तत्। अवीवृतत्-अववर्तत्। अमीमृजत्-अममार्जत्। 'पातेर्णौ लुग्वक्तव्यः' (वा ४५२०)। पुकोऽपवादः। पालयति।

२५९०। वो विधूनने जुक्। ७। ३। ३८। वातेर्जुक्स्याण्णौ कम्पेऽर्थे। वाजयति। 'कम्पे' किम्। केशान्वापयति। 'विभाषा लीयतेः' (सू २५०९)।

२५९१। लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने। ७। ३। ३९। लीयतेर्लातेश्च

क्रमान्नुग्लुकावागमौ वा स्तो णौ स्नेहद्रवे । विलीनयति–विलापयति–विलालयति–विलापयति वा घृतम् । 'ली' 'ई' इति ईकारप्रश्लेषादात्त्वपक्षे नुग्न । 'स्नेहद्रवे' किम् । लोहं विलापयति । 'प्रलम्भनाभिभवपूजासु लियो नित्यमात्त्वमशिति वाच्यम्' (वा ३४८३) ।

२५९२ । लियः संमाननशालीनीकरणयोश्च । १ । ३ । ७० । लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यादकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते वञ्चयतीत्यर्थः ।

२५९३ । बिभेतेर्हेतुभये । ६ । १ । ५६ । बिभेतेरेच आत्त्वं वा स्यात्प्रयोजकाद्भयं चेत् ।

२५९४ । भीस्म्योर्हेतुभये । १ । ३ । ६८ । ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ।

२५९५ । भियो हेतुभये षुक् । ७ । ३ । ४० । 'भी' 'ई' इति ईकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक्स्याण्णौ हेतुभये । भीषयते ।

२५९६ । नित्यं स्मयतेः । ६ । १ । ५७ । स्मयतेरेचो नित्यमात्त्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति । कथं तर्हि 'विस्मापयन्विस्मितमात्मवृत्तौ' इति । 'मनुष्यवाचा' इति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । 'विस्माययन्' इत्यत्र पाठ इति सांप्रदायिकाः । यद्वा । मनुष्यवाक्प्रयोज्यकर्त्री विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ 'शता' इति व्याख्येयम् ।

२५९७ । स्फायो वः । ७ । ३ । ४१ । णौ । स्फावयति ।

२५९८ । शदेरगतौ तः । ७ । ३ । ४२ । शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु गाः शादयति गोविन्दः । गमयतीत्यर्थः ।

२५९९ । रुहः पोऽन्यतरस्याम् । ७ । ३ । ४३ । णौ रोपयति–रोहयति ।

२६०० । क्रीङ्जीनां णौ । ६ । १ । ४८ । एषामेच आत्त्वं स्याण्णौ क्रापयति । अध्यापयति । जापयति ।

२६०१ । णौ च संश्चङोः । २ । ४ । ५१ । सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अध्यजीगपत् । अध्यापिपत् ।

२६०२ । सिध्यतेरपारलौकिके । ६ । १ । ४९ । ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्त्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । 'अपारलौकिके' किम् । तापसः सिध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ।

२६०३ । प्रजने वीयतेः । ६ । १ । ५५ । अस्यैच आत्त्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति–वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । 'ऊदुपधाया गोहः' (सू २३११) । गूहयति ।

२६०४ । दोषो णौ । ६ । ४ । ९० । 'दुषः' इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ।

२६०५ । वा चित्तविरागे । ६ । ४ । ९१ । विरागोऽप्रीतता । चित्तं दूषयति–दोषयति वा कामः । 'मितां ह्रस्वः' (सू २५६८) । भ्वादौ चुरादौ च मित उक्ताः । घटयति ।

'जनीजृष्-'। जनयति-जरयति। जृणातेस्तु। जारयति। 'रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः' (वा ४०६७)। मृगरमणमाखेटकम्। रजयति मृगान्। 'मृग-' इति किम्। रञ्जयति पक्षिणः। रमणादन्यत्र तु रञ्जयति मृगान्तृणदानेन। चुरादिषु ज्ञपादिश्चिञ्। 'चिस्फुरोर्णौ' (सू २५६९)। चपयति-चययतीत्युक्तम्। चिनोतेस्तु। चापयति-चाययति। स्फारयति-स्फोरयति। अपुस्फरत्-अपुस्फुरत्।

२६०६। उभौ साभ्यासस्य। ८। ४। २१। साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति। प्राणिणत्।

२६०७। णौ गमिरबोधने। २। ४। ४६। इणो गमिः स्याण्णौ। गमयति। बोधने तु प्रत्याययति। 'इण्वदिकः' (वा १९७७)। अधिगमयति। 'हनस्तोऽचिण्णलोः' (सू २५७४)। 'हो हन्तेः' इति कुत्वम्। घातयति। 'ईर्ष्यतेस्तृतीयस्येति वक्तव्यम्' (वा ३४०३) तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः। आद्ये षकारस्य द्वित्वं वारयितुमिदम्। द्वितीये तु 'अजादेर्द्वितीयस्य' (सू २१७६) इत्यस्यापवादतया सन्नन्ते प्रवर्तते। ऐर्ष्यियत्-ऐर्षिष्यत्। द्वितीयव्याख्यायां। णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते। हलादिःशेषात्। द्वित्वं तु द्वितीयस्यैव। तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः। निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः। तेन 'प्रार्थयन्ति शयनोत्थितं प्रियाः' इत्यादि सिद्धम्। एवं सकर्मकेषु सर्वेषूह्यम्।

इति तिङन्तणिच्प्रकरणम्।

अथ तिङन्तसन्प्रकरणम्।

२६०८। धातोः कर्मणः समानकर्तृकादिच्छायां वा। ३। १। ७। इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम्। धातोर्विहितत्वादिह सन आर्धधातुकत्वम्। इट्। द्वित्वम्। 'सन्यतः' (सू २३१७)। पठितुमिच्छति पिपठिषति। 'कर्मणः' किम्। गमनेनेच्छतीति करणान्मा भूत्। 'समानकर्तृकात्' किम्। शिष्याः पठन्त्वितीच्छति गुरुः। वाग्रहणात्पक्षे वाक्यमपि। 'लुङ्सनोर्घस्लृ' (सू २४२७)। 'एकाच उपदेशे-' (सू २२४६) इति नेट्। सस्य तत्वम्। अत्तुमिच्छति। जिघत्सति। 'ईर्ष्यतेस्तृतीयस्य (वा ३४०३) इति यिसनोर्द्वित्वम्। इर्ष्यियिषति-ईर्ष्यिषिषति।

२६०९। रुदविदमुषग्रहिस्वपिप्रच्छः संश्च। १। २। ८। एभ्यः संश्च क्त्वा च कितौ स्तः। रुरुदिषति। विविदिषति। मुमुषिषति। पि

२६१०। सनि ग्रहगुहोश्च। ७। २। १२। ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात्। 'ग्रहिज्या-' (सू २४१२) इति संप्रसारणम्। सनः षत्वस्यासिद्धत्वाद्भष्भावः। जिघृक्षति। जुघुक्षति।

२६११। किरश्च पञ्चभ्यः। ७। २। ७५। 'कृ' 'गृ' 'दृङ्' 'धृङ्' 'प्रच्छ' एभ्यः सन इट् स्यात्। पिपृच्छिषति। चिकरिषति। जिगरिषति। जिगलिषति। अनेटो दीर्घो नेटः। दिदरिषते। दिधरिषते। कथम् 'उद्दिधीर्षुः' इति। भौवादिकयोर्धृङ्धृञोरिति गृहाण।

२६१२। इको झल्। १। २। ९। इगन्ताज्झलादिः सन्कित्स्यात्। बुभूषति। दीङ्।

दातुमिच्छति दिदीषते। एज्विषयत्वाभावात् 'मीनातिमिनोति-' (सू २५०८) इत्यात्त्वं न। अत एव 'सनि मीमा-' (सू २६२३) इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम्।

२६१३। हलन्ताच्च। १। २। १०। इक्समीपाद्धलः परो झलादिः सन्कित्स्यात्। गुहू। जुघुक्षति। बिभित्सति। 'इकः' किम्। यियक्षते। 'झल्' किम्। अविवर्धिषते। हल्ग्रहणं जातिपरम्। तृंहू तितृक्षति तितृंहिषति।

२६१४। अज्झनगमां सनि। ६। ४। १६। अजान्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि। 'सन्लिटोर्जेः' (सू २३३१)। जिगीषति। 'विभाषा चेः' (सू २५२५)। चिकीषति-चिचीषति। जिघांसति।

२६१५। सनि च। २। ४। ४७। इणो गमिः स्यात्सनि न तु बोधने। जिगमिषति। बोधने प्रतीषिषति। 'इण्वदिकः' (वा १५७७)। अधिजिगमिषति। कर्मणि तङ्। 'परस्मैपदेषु' इत्युक्तेर्नेट्। 'झलादौ सनि' इति दीर्घः। जिगांस्यते। अधिजिगांस्यते। अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः। जिगंस्यते। संजिगंसते।

२६१६। इङश्च। २। ४। ४८। इङो गमिः स्यात्सनि। अधिजिगांसते।

२६१७। रलो व्युपधाद्धलादेः संश्च। १। २। २६। उश्च इश्च वी। ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। 'द्युतिस्वाप्योः संप्रसारणम्' (सू २३४४)। दिद्युतिषते-दिद्योतिषते। रुरुचिषते-रुरोचिषते। लिलिखिषति-लिलेखिषति। 'रलः' किम्। दिदेविषति। 'व्युपधात्' किम्। विवर्तिषते। 'हलादेः' किम्। एषिषिषति। इह नित्यमपि द्वित्वं गुणेन बाध्यते। 'उपधाकार्यं हि द्वित्वात्प्रबलम्'। ओणेर्ऋदित्करणस्य सामान्यापेक्षज्ञापकत्वात्।

२६१८। सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्। ७। २। ४९। इवन्तेभ्यः र्धादिभ्यश्च सन इड्वा स्यात्। इडभावे 'हलन्ताच्च' (सू २६१३) इति कित्त्वम्। 'च्छ्वोः-' (सू २५६१) इति वस्य ऊठ्। यण्। द्वित्वम्। दुद्यूषति-दिदेविषति। 'स्तौतिण्योरेव-' (सू २६२७) इति वक्ष्यमाणनियमान्न षः। सुस्यूषति-सिसेविषति।

२६१९। आप्ज्ञप्यृधामीत्। ७। ४। ५५। एषामच ईत्स्यात्सादौ सनि।

२६२०। अत्र लोपोऽभ्यासस्य। ७। ४। ५८। 'सनि मीमा-' (सू २६२३) इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात्। आप्तुमिच्छति ईप्सति। आर्धितुमिच्छति। रपरत्वम्। चर्त्वम्। ईर्त्सति-आर्दिधिषति। बिभ्रज्जिषति-बिभर्जिषति-भिभ्रक्षति-बिभर्क्षति।

२६२१। दम्भ इच्च। ७। ४। ५६। दम्भेरच इत्स्यादीच्च सादौ सनि, अभ्यासलोपः। 'हलन्ताच्च' (सू २६१३) इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम्। तेन सनः कित्त्वान्न लोपः। धिप्सति-धीप्सति-दिदम्भिषति। शिश्रीषति-शिश्रयिषति। 'उदोष्ठ्यपूर्वस्य' (सू २४९४)। सुस्वूर्षति-सिस्वरिषति। युयूषति-यियविषति। ऊर्णुनूषति-ऊर्णुनुविषति-ऊर्णुनाविषति। न च परत्वाद्गुणावादेशयोः सतोरभ्यास उकारो न श्रूयेतेति वाच्यम्। 'द्विर्वचनेऽचि' (सू २२४३) इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशाददेशनिषेधाद्वा। न च सन्नन्तस्य द्वित्वं प्रति कार्यत्वान्निमित्तता कथमिति वाच्यम्। 'कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते न त्वननुभवन्नपि' (प ११)। न चेह सन्द्वित्वमनुभवति। बुभूर्षति-बिभरिषति। ज्ञपिः पुगन्तो

मित्संज्ञः पकारान्तश्चौरादिकश्च । इडभावे 'इको झल्' (सू २६१२) इति कित्त्वात्र गुणः । 'अज्झन–'(सू २६१४) इति दीर्घः परत्वाण्णिलोपेन बाध्यते । 'आप्ज्ञपि–'(सू २६१९)इति ईत् । ज्ञीप्सति–जिज्ञपयिषति । अमितत्त्वे तु जिज्ञापयिषति । 'जनसन–' (सू २५०४) इत्यात्त्वम् । सिषासति–सिसनिषति । '[1]तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः' (वा ५०५९) ।

२६२२ । तनोतेर्विभाषा । ६ । ४ । १७ । अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति–तितंसति–तितनिषति । 'आशङ्कायां सन्वक्तव्यः' (वा १७०७) । श्वा मुमूर्षति । कूलं पिपतिषति ।

२६२३ । सनि मीमाघुरभलभशकपतपदामच इस् । ७ । ४ । ५४ । एषामच इत्स्यात्सादौ सनि । अभ्यासलोपः । 'स्कोः–' (सू ३८०) इति सलोपः । पित्सति । दिदरिद्रिषति–दिदरिद्रासति । 'डुमिञ्' 'मीञ्' आभ्यां सन् । कृतदीर्घस्यमिनोतेरपि मीरूपाविशेषादिस् । 'सः सि–' (सू २३४२) इति तः । मित्सति । मित्सते । 'मा' माने । मित्सति । माङ्मेङोः । मित्सते । 'दोदाणोः' । दित्सति । 'देङ्' । दित्सते । 'दाञ्' । दित्सति–दित्सते । 'धेट्' । धित्सति । 'धाञ्' धित्सति–धित्सते । रिप्सते । लिप्सते । 'शक्लृ' । शिक्षति । 'शक मर्षणे' इति दिवादिः । स्वरितेत् । शिक्षति–शिक्षते । पित्सते । 'राधो हिंसायां सनीस् वाच्यः' (वा ४६३५) । रित्सति । 'हिंसायाम्' किम् । आरिरात्सति ।

२६२४ । मुचोऽकर्मकस्य गुणो वा । ७ । ४ । ५७ । सादौ सनि । अभ्यासलोपः । मोक्षते–मुमुक्षते वा वत्सः स्वयमेव । 'अकर्मकस्य' किम् । मुमुक्षति वत्सं कृष्णः । 'न वृद्भ्यश्चतुर्भ्यः' (सू २३४८) । विवृत्सति । तङि तु । विवर्तिषते । 'सेऽसिचि–' (सू २५०६) इति वेट् । निनर्तिषति–निनृत्सति ।

२६२५ । इट् सनि वा । ७ । २ । ४१ । वृङ्वृञ्भ्यामृदन्ताच्च सन इड्वा स्यात् । तितरिषति–तितरीषति–तितीर्षति । विवरिषति–विवरीषति–वुवूर्षति । 'वृङ्' । वुवुर्षते–विवरिषते । दुध्वूर्षति ।

२६२६ । स्मिपूङ्रञ्ज्वशां सनि । ७ । २ । ७४ । 'स्मिङ्' 'पुङ्' 'ऋ' 'अञ्जू' 'अशू' एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषते । इह 'रिस्' शब्दस्य द्वित्वम् । 'इस' इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् 'द्विर्वचनेऽचि' (सू २२४३) इति न प्रवर्तते । अञ्जिजिषति । अशिशिषते । 'उभौ साभ्यासस्य' (सू २६०६) । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । 'पूर्वत्रासिद्धीयमद्वित्वे' इति चछाभ्यां सहितस्येटो द्वित्वम् । 'हलादिः शेषः' (सू २१७९) । उचिच्छिषति । 'निमित्तापाये नैमित्तिकापायः' इति त्वनित्यम् । 'च्छ्वोः–' (सू २५६१) इति सतुक्ग्रहणाज्ज्ञापकात् । प्रकृतिप्रत्यापत्तिवचनाद्वा–' । 'णौ च संश्चङोः' (सू २५७९) (सू २६०१) इति सूत्राभ्यामिङो गाङ्, श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति–अध्यापिपयिषति । शिश्वाययिषति–शुशावयिषति । 'ह्वः संप्रसारणम्' (सू २५८६) । जुहावयिषति । 'णौ द्वित्वात्प्रागच आदेशो न' इत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षावयिषति । 'ओः पुयण्ज्यपरे' (सू २५७७) । पिपावयिषति । यियावयिषति ।

---

[1] इदं च 'सनीवन्त–' (सू २६१८) इति सूत्रेएव 'भरज्ञपिसनितनिपतिदरिद्राणाम्' इति केचित्पठन्तीति सूत्रशेषभूतमिति काशिका । अपरं वार्तिकमेवाति कैयटाशयः ।

बिभावयिषति। रिरावयिषति। लिलावयिषति। जिजावयिषति। 'पुयण्जि' इति किम्। नुनावयिषति। 'अपरे' किम्। बुभूषति। 'स्रवति-' (२९७८) इतीत्त्वं वा। सिस्रावयिषति। सुस्रावयिषतीत्यादि। 'अपरे' इत्येव। शुश्रूषते।

२६२७। स्तौतिण्योरेव षण्यभ्यासात्। ८।३।६१। अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य षः स्यात्षभूते सनि नान्यस्य। तुष्टूषति। 'शुतिस्वाप्योः-' (सू २३४४) इत्युत्त्वम्। सुष्वापयिषति। सिषाधयिषति। 'स्तौतिण्योः' किम्। सिसिक्षति। उपसर्गात्तु 'स्थादिष्वभ्यासेन च-' (सू २२७७) इति षत्वम्। परिषिषिक्षति। 'षणि' किम्। तिष्ठासति। सुष्वप्सति। अभ्यासादित्युक्तेर्नेह निषेधः। इण्। प्रतीषिषति। इक्। अधीषिषति।

२६२८। स स्विदिस्वदिसहीनां च। ८।३।६२। अभ्यासेणः परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे। सिस्वेदयिषति-सिस्वादयिषति। सिसाहयिषति। 'स्थादिष्वेवाभ्यासस्य' इति नियमान्नेह। अभिसुसूषति।

'शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः।
सरूपप्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते॥' (भाष्यम्)

शैषिकाच्छैषिकः सरूपो न। तेन शालीये भव इति वाक्यमेव न तु छान्ताच्छः। 'सरूपः' किम्। अहिच्छत्रे भव आहिच्छत्रः। आहिच्छत्रे भव आहिच्छत्रीयः। अण्णन्ताच्छः। तथा मत्वर्थात्सरूपः स न। धनवानस्यास्ति। इह मतुबन्तान्मतुब्न। विरूपस्तु स्यादेव। दण्डिमती शाला। 'सरूपः' इत्यनुषज्यते। अर्थद्वारा सादृश्यं तस्यार्थः। तेन इच्छसन्नन्तात्सन्न। स्वार्थसन्नन्तात्तु स्यादेव। जुगुप्सिषते। मीमांसिषते।

इति तिङन्तसन्प्रकरणम्।

अथ तिङन्तयङ्प्रकरणम्।

२६२९। धातोरेकाचो हलादेः क्रियासमभिहारे यङ्। ३।१।२२। पौनःपुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन्द्योत्ये यङ् स्यात्।

२६३०। गुणो यङ्लुकोः। ७।४।८२। अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च। 'सनाद्यन्ताः-' (सू २६०४) इति धातुत्वाल्लडादयः। ङिदन्तत्वादात्मनेपदम्। पुनः पुनरतिशयेन वा भवति बोभूयते। बोभूयांचक्रे। अबोभूयिष्ट। 'धातोः' किम्। आर्धधातुकत्वं यथा स्यात्। तेन 'ब्रुवो वचिः' (सू २४९३) इत्यादि। 'एकाचः' किम्। पुनःपुनर्जागर्ति। 'हलादेः' किम्। भृशमीक्षते। भृशं शोभते रोचत इत्यत्र यङ्नेति भाष्यम्। पौनःपुन्ये तु स्यादेव। रोरुच्यते। शोशुभ्यते। 'सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः' (वा १७९१)। आद्यास्त्रयश्चुरादावदन्ताः। सोसूच्यते। सोसूत्र्यते। अनेकाच्त्वेनाषोपदेशत्वात्षत्वं न। मोमूत्र्यते।

२६३१। यस्य हलः। ६।४।४९। 'यस्य' इति संघातग्रहणम्। हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके। 'आदेः परस्य' (सू ४४)। 'आतो लोपः' (सू २३०८)। सोसूचांचक्रे। सोसूचिता। सोसूत्रिता। मोमूत्रिता।

२६३२ । दीर्घोऽकितः । ७ । ४ । ८३ । अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ।

२६३३ । यङि च । ७ । ४ । ३० । अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि । यकारपररेफस्य न द्वित्वनिषेधः । 'अरार्यते' इति भाष्योदाहरणात् । अरारिता । अशाशिता । ऊर्णोनुयते । बेभिद्यते । अल्लोपस्य स्थानिवत्त्वान्नोपधागुणः । बेभिदिता ।

२६३४ । नित्यं कौटिल्ये गतौ । ३ । १ । २३ । गत्यर्थात्कौटिल्य एव यङ्स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ।

२६३५ । लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् । ३ । १ । २४ । एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ।

२६३६ । चरफलोश्च । ७ । ४ । ८७ । अनयोरभ्यासस्यातो नुक्स्याद्यङ्लुकोः । 'नुक्' इत्यनेनानुस्वारो लक्ष्यते । 'स च पदान्तवद्वाच्यः' (वा ४६६१) 'वा पदान्तस्य' (सू १२९) इति यथा स्यात् ।

२६३७ । उत्परस्यातः । ७ । ४ । ८८ । चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । 'हलि च' (सू ३५४) इति दीर्घः । चञ्चूर्यते-चंचूर्यते । पम्फुल्यते-पंफुल्यते ।

२६३८ । जपजभदहदशभञ्जपशां च । ७ । ४ । ८६ । एषामभ्यासस्य नुक्स्याद्यङ्यङ्लुकोः । गर्हितं जपति जञ्जप्यत इत्यादि ।

२६३९ । ग्रो यङि । ८ । २ । २० । गिरते रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति जेगिल्यते । 'घुमास्था-' (सू २४६२) । इतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । 'विभाषा श्वेः' (सू २४२०) । शोशूयते । शेश्वीयते । 'यङि च' (सू २६३३) । सास्मर्यते । 'रीङृतः' (सू १२३४) । चेक्रीयते । सुट् । संचेस्क्रीयते ।

२६४० । सिचो यङि । ८ । ३ । ११२ । सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ।

२६४१ । न कवतेर्यङि । ७ । ४ । ६३ । कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ।

२६४२ । नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् । ७ । ४ । ८४ । एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः । 'अकितः' इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यत इत्यादि ।

२६४३ । नुगतोऽनुनासिकान्तस्य । ७ । ४ । ८५ । अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक्स्यात् । नुकानुस्वारो लक्ष्यत इत्युक्तम् । यंय्यम्यते-यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । 'भाम' क्रोधे । बाभाम्यते । 'ये विभाषा' (२३१९) । जाजायते-जञ्जन्यते । 'हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः' (वा ४६२१) । जेघ्नीयते । 'हिंसायाम्' किम् । जङ्घन्यते ।

२६४४ । रीगृदुपधस्य च । ७ । ४ । ९० । ऋदुपधस्य धोतारभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते । क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीक्लृप्यते । 'रीगृत्वत इति वक्तव्यम्' (वा ४६६२) । वरीवृश्च्यते । परीपृच्छ्यते ।

२६४५ । स्वापिस्यमिव्येञां यङि । ६ । १ । १९ । संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ।

२६४६। न वशः। ६। १। २०। वावश्यते।
२६४७। चायः की। ६। १। २१। चेकीयते।
२६४८। ई घ्राध्मोः। ७। ४। ३१। जेघ्रीयते। देध्मीयते।
२६४९। अयङ्यि क्ङिति। ७। ४। २२। शीङोऽयङादेशः स्याद्यादौ क्ङिति परे। शाशय्यते। आभ्यासस्य ह्रस्वः। ततो गुणः। डोढौक्यते। तोत्रौक्यते।

इति तिङन्तयङ्प्रकरणम्।

अथ तिङन्तयङ्लुक्प्रकरणम्।

२६५०। यङोऽचि च। २। ४। ७४। यङोऽच्प्रत्यये लुक्स्याच्चकारात्तं विनापि बहुलं लुक्स्यात्। अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति। ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम्। अभ्यासकार्यम्। धातुत्वाल्लडादयः। 'शेषात्कर्तरि–' (सू २१५९) इति परस्मैपदम्। 'अनुदात्तङितः–' (सू २१५७) इति तु न। ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः। यत्र हि 'प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्'। अत एव सुदृषत्प्रासाद इत्यत्र 'अत्वसन्तस्य–' (सू ४२९) इति दीर्घो न। येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न। 'अनुदात्तङितः–' (सू २१५७) इत्यनुबन्धनिर्देशात्। तत्र च 'श्तिपा शपा–' (प १३२) इति निषेधात्। अत एव श्यनादयो न। गणेन निर्देशात्। किं तु शबेव। 'चर्करीतं च' इत्यदादौ पाठाच्छपो लुक्।

२६५१। यङो वा। ७। ३। ९४। यङन्तात्परस्य हलादेः पितः सार्वधातुकस्येड्वा स्यात्। 'भूसुवोः–' (सू २२२४) इति गुणनिषेधो यङ्लुकि भाषायां न। '–बोभूतुतेतिक्ते' (सू ३५९६) इति छन्दसि निपातनात्। अत एव यङ्लुग्भाषायामपि सिद्धः। न च यङ्लुक्यप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम्। 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्' (प १०१)। 'द्विः प्रयोगो द्विर्वचनं षाष्ठम्' इति सिद्धान्तात्। बोभवीति–बोभूतः–बोभोति। बोभुवति। बोभवांचकार। बोभविता। अबोभवीत्–अबोभोत्। अबोभूताम्। अबोभवुः। बोभूयात्। बोभूयाताम्। बोभूयास्ताम्। 'गातिस्था–' (सू २२२३) इति सिचो लुक्। 'यङो वा' (सू २६५१) इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक्। अबोभूवीत्। अबोभूत। अबोभूताम्। अभ्यस्ताश्रयो जुस्। नित्यत्वाद्वुक्। अबोभूवुः। अबोभविष्यदित्यादि। पास्पर्धीति–पास्पर्धि। पास्पर्धः। पास्पर्धति। पास्पर्त्सि। 'हुझल्भ्यो हेर्धिः' (सू २४२५)। पास्पर्धि। लङ्। अपास्पर्त्–अपास्पर्द्। सिपि 'दश्च' (सू २४६८) इति रुत्वपक्षे 'रो रि' (सू १७३) अपास्पाः। जागाद्धि। जाघात्सि। अजाघात् सिपि रुत्वपक्षे। अजाघाः। 'नाथृ'। नानात्ति। नानात्तः। 'दध'। दादद्धि। दादद्धः। दाधत्सि। अदाधत्। अदादधुः। अदाधः। अदाधत्। लुङि। अदादाधीत्–अदादधीत्। चोस्कुन्दीति–चोस्कुन्ति। अचोस्कुन्। अचोस्कुन्ताम्। अचोस्कुन्दुः। मोमुदीति–मोमोत्ति। मोमोदांचकार। मोमोदिता। अमोमुदीत्–अमोमोत्। अमोमुत्ताम्। अमोमुदुः। अमोमुदीः–अमोमोः। अमोमोत्। लुङि गुणः। अमोमोदीत्। चोकुर्ति–चोकुर्दीति। लङि तिप्। अचोकूर्त्–अचोकूर्दीत्। सिप्पक्षे। अचोकूः। अचोखूः। अजोगूः। वनीवञ्चीति–वनीवङ्क्ति। वनीवक्तः। वनीवचति। अवनीवञ्चीत्। अवनीवन्। जङ्गमीति–जङ्गन्ति। 'अनु-

दात्तोपदेश–' (सू २४२८) इत्यनुनासिकलोपः। जङ्गतः। जङ्गमति। 'म्वोश्च' (सू २३०९)। जङ्गन्मि। जङ्गन्वः। एकाज्ग्रहणोक्तत्वान्नेण्निषेधः। जङ्गमिता। अनुनासिकलोपस्याभीयत्वे-नासिद्धत्वान्न हेर्लुक्। जङ्गहि। 'मो नो धातोः' (सू ३४१)। अजङ्गन्। अनुबन्धनिर्देशान्न च्लेरङ्। 'ह्म्यन्त–' (सू २२९९) इति न वृद्धिः। अजङ्गमीत्। अजङ्गमिष्टाम्। हन्तेर्यङ्लुक्। 'अभ्यासाच्च' (सू २४३०) इति कुत्वं यद्यपि 'हो हन्तेः–' (सू ३५८) इत्यतो 'हन्तेः' इत्यनुवर्त्त्य विहितं तथापि यङ्लुकि भवत्येवेति न्यासकारः। 'श्तिपाशपा' (प १३२) इति निषेधस्त्वनित्यः। 'गुणो यङ्लुकोः' (सू २६३०) इति सामान्यापेक्षज्ञापकादिति भावः। जङ्घनीति। जङ्घन्ति। जङ्घतः। जङ्घ्नति। जङ्घनिता। श्तिपानिर्देशाज्जादेशो न। जङ्घहि। अजङ्घनीत्। अजङ्घन्। जङ्घन्यात्। आशिषि तु वध्यात्। अवधीत्। अवधिष्टामित्यादि। वधादेशस्य द्वित्वं न भवति। स्थानिवत्त्वेन 'अनभ्यासस्य' इति निषेधात्। तद्धि समानाधिकरणं धातोर्विशेषणम्। बहुव्रीहिबलात्। अङ्पूर्वात्तु 'आङो यमहनः' (सू २६९५) इत्यात्मनेपदम्। आजङ्घत इत्यादि। 'उत्परस्य–' (सू २६२७) इति तपरत्वान्न गुणः। 'हलि च' (सू ३५४) इति दीर्घस्तु स्यादेव। तस्यासिद्धत्वेन तपरत्वानिवर्त्यत्वायोगात्। चञ्चुरीति–चञ्चूर्ति। चञ्चूर्तः। चञ्चुरति। अचञ्चुरीत्। अचञ्चूः। चङ्खनीति। चङ्खन्ति। 'जनसन–' (सू २५०४) इत्यात्त्वम्। चङ्खातः। 'गमहन–' (सू २३६३) इत्युपधालोपः। चङ्ख्नति। चङ्खाहि। चङ्खनानि। अचङ्खनीत्–अचङ्खनीत्। अचङ्खन्। अचङ्ख्नुः। 'ये विभाषा' (सू २३१९)। चङ्खायात्–चङ्खन्यात्। अचङ्खनीत्–अचङ्खानीत्। 'उतो वृद्धिः–' (सू २४४३) इत्यत्र 'नाभ्यस्तस्य' इत्यनुवृत्तेरुतो वृद्धिर्न। योयोति–योयवीति। अयोयवीत्–अयोयोत्। योयुयात्। आशिषि दीर्घः। योयूयात्। अयोयावीत्। नोनवीति–नोनोति। जाहेति–जाहाति। 'ई हल्यघोः' (सू २४९७)। जाहीतः। इह 'जहातेश्च' (सू २४९८) 'आ च हौ' (सू २४९९) 'लोपो यि' (सू २५००) 'घुमास्था' (सू २४६२) 'एर्लिङि' (स २३७४) इत्येते पञ्चापि न भवन्ति। श्तिपा निर्देशात्। जाहाति। जाहासि–जाहेषि। जाहीथः। जाहीथ। जाहीहि। अजाहेत्। अजाहात्। अजाहीताम्। अजाहुः। जाहीयात्। आशिषि जाहायात्। अजाहासीत्। अजाहासिष्टाम्। अजाहिष्यत्। लुका लुप्ते प्रत्ययलक्षणाभावात् 'स्वपिस्यमि–' (सू २६४५) इत्युत्वं न। 'रुदादिभ्यः–' (सू २४७४) इति गणनिर्दिष्टत्वादिण्न। सास्वपीति–सास्वप्ति। सास्वप्तः। सास्वपति। असास्वपीत्–असास्वप्। सास्वप्यात्। आशिषि तु 'वचिस्वपि–' (सू २४०९) इत्युत्वम्। सासुप्यात्। असास्वापीत्। असास्वपीत्।

२६९२। रुग्रिकौ च लुकि। ७। ४। ९१। ऋदुपधस्य धातोरभ्यासस्य 'रुक्' 'रिक्' 'रीक्' एत आगमाः स्युर्यङ्लुकि।

२६९३। ऋतश्च। ७। ४। ९२। ऋदन्तधातोरपि तथा। वर्वृतीति–वरिवृतीति–वर्वर्ति–वरिवर्ति–वरीवर्ति। वर्वृतः–वरिवृतः–वरीवृतः। वर्वृतति–वरिवृतति–वरीवृतति। वर्वर्तामास–वरिवर्तामास–वरीवर्त्तामास। वर्वर्तिता–वरिवर्तिता–वरीवर्तिता। गणनिर्दिष्टत्वात् 'न वृद्भ्यश्चतुर्भ्यः' (सू २३४८) इति न। वर्वर्तिष्यति–वरिवर्तिष्यति–वरीवर्तिष्यति। अवर्वृतीत्–अवरिवृतीत्–अवरीवृतीत्। अवर्वर्त्–अवरिवर्त्–अवरीवर्त्। सिपि 'दश्च' (सू २४६८) इति रुत्वपक्षे 'रो रि' (१७३) अवर्वाः–अवरिवाः–अवरीवाः। गणनिर्दिष्टत्वादङ्। अवर्वर्तीत्–अवरिवर्तीत्–अवरीवर्तीत्। चर्करीति–चर्कर्ति–चरिकर्ति–चरीकर्ति। चर्कृतः। चर्क्रति। चर्करांचकार। चर्करिता।

अचर्करीत् । अचर्कः । चर्कृयात् । आशिषि रिङ् । चर्क्रियात् । अचर्कारीत् । 'ऋतश्च' (सू २६९३) इति तपरत्वान्नेह । 'कॄ विक्षेपे' । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङ्लुकि द्वित्वेऽभ्यासस्योरत्त्वं रपरत्वम् । 'हलादिः शेषः' (सू २१७९) रुक् । रिग्रीकोस्तु 'अभ्यासस्यासवर्णे' (सू २२९०) इति इयङ् । अरर्ति-अरियर्ति-अररीति-अरियरीति । अर्ऋतः । अरियृतः । झि अत् । यण्रुकौ 'रो रि' (सू १७३) इति लोपः । न च तास्मिन्कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धे तन्निषेधात् । आरति । आरियति । लिङि श्तिपानिर्देशात् 'गुणोऽर्ति-'(सू २३८०) इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात्-अरिरियात्-अरीरियात् । 'गृहू ग्रहणे' । जर्गृहीति । जर्गार्ढि । जर्गृढः । जर्गृहति । अजर्घर्ट् । गृह्णातेस्तु जाग्रहीति-जाग्राढि । तसादौ ङिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेना-सिद्धत्वान्न रुगादयः । जागृढः । जागृहति । जाग्रहीषि-जाग्रक्षि । लुटि । जाग्रहिता । 'ग्रहोऽलिटि'-(सू २५६२) इति दीर्घस्तु न । तत्र 'एकाचः' इत्यनुवृत्तेः । माधवस्तु दीर्घमाह तद्भाष्यविरुद्धम् । जर्गृधीति । जर्गर्धि । जर्गृद्धः । जर्गृधतिः । जर्गृधीषि-जर्घर्त्सि । अजर्गृधीत् । इडभावे गुणः । हलङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घत् । अजर्गृद्धाम् । सिपि 'दश्च' (सू २६६८) इति पक्षे रुत्वम् । अजर्घाः । अजर्गर्धीत् । अजर्गर्धिष्टाम् । पाप्रष्टि । तसादौ 'ग्रहिज्या-'(सू २४१२) इति संप्रसारणं न भवति श्तिपा निर्देशात् । 'च्छ्वोः शूठ्-'(सू २५६१) इति शः । 'व्रश्च-' (सू २९४) इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः । 'यकारवकारान्तानां तु ऊठ्भाविनां यङ्लुङ्नास्ति' इति 'च्छ्वोः-'(सू २५६१) इति सूत्रे भाष्ये ध्वनितम् । कैयटेन स्पष्टीकृतम् । इदं च 'च्छ्वोः-' (सू २५६१) इति यत्रोठ् तद्विषयकम् । 'ज्वरत्वर-'(सू २६५४) इत्यूठ्भाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यम् । माधवादिसंमतं च । 'मव्य बन्धने' । अयं यान्त ऊठ्भावी । 'तेवृ देवृ देवने' इत्यादयो वान्ताः । 'हय गतौ' । जाहयीति-जाहति । जाहतः । जाहयति । जाहयीषि-जाहसि । बलि लोपे । यञादौ दीर्घः । जाहामि । जाहावः जाहामः । 'हर्य गतिकान्त्योः' । जाहर्यीति-जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । 'मव बन्धने' ।

२६५४ । ज्वरत्वरस्रिव्यविमवामुपधायाश्च । ६ । ४ । २० । ज्वरादीनामुपधावकारयोरूठ् स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि 'ओतुः' इति दर्शनात् । अनुनासिकग्रहणं चानुवर्तते । अवतेर्मनिन्प्रत्यये तस्य टिलोपे 'ओम्' इति दर्शनादीडभाव ऊठि पिति गुणः । मामोति-मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामोतु । मामूतात् । मामूहि । मामवानि । अमामोत् । अमामोः । अमामवम् । अमामाव । अमामूम । 'तुर्वी हिंसायाम्' । तोतूर्वीति ।

२६५५ । राल्लोपः । ६ । ४ । २१ । रेफात्परयोश्छ्वोर्लोपः स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ।

२६५६ । न धातुलोप आर्धधातुके । १ । १ । ४ । धात्वंशलोपनिमित्त आर्धधातुके परे इको गुणवृद्धी न स्तः । इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् ।

तोतोर्ति । 'हलि च' (सू ३५४) इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । 'मूर्च्छा' । मोमोर्ति । मोमूर्तः । मोमूर्च्छतीत्यादि । 'आर्धधातुके' इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वासंभवेन वीभावस्याप्रवृत्तेः ।

इति तिङन्तयङ्लुक्प्रकरणम् ।

अथ तिङन्तनामधातुप्रकरणम् ।

२६५७ । सुप आत्मनः क्यच् । ३ । १ । ८ इषिकर्मण एषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच्प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ।

२६५८ । क्यचि च । ७ । ४ । ३३ । अस्य 'ईत्' स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । 'वान्तो यि प्रत्यये' (सू ६३) गव्यति । नाव्यति । 'लोपः शाकल्यस्य' (सू ६७) इति तु न । अपदान्तत्वात् । तथा हि ।

२६५९ । नः क्ये । १ । ४ । १५ । क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । संनिपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता । नलोपः । राजीयति । 'प्रत्ययोत्तरपदयोश्च' (सू १३७३) । त्वद्यति । मद्यति । 'एकार्थयोः' इत्येव । युष्मद्यति । अस्मद्यति 'हलि च' (सू ३५४) । गीर्यति । पूर्यति । 'धातोः' इत्येव । नेह । दिवमिच्छति दिव्यति । इह पुरमिच्छति पुर्यतीति माधवोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । 'रीङृतः' (सू १२३४) । कर्त्रीयति । 'क्यच्व्योश्च' (सू २११९) । गार्गीयति । वाच्यति । 'अकृत्सार्व-' (सू २२९८) इति दीर्घः । कवीयति । समिध्यति ।

२६६० । क्यस्य विभाषा । ६ । ४ । ५० । हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । 'आदेः परस्य' (सू ४४) । 'अतो लोपः' (सू २३०८) । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता । 'मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न' (वा १७१४) । किमिच्छति । इदमिच्छति । स्वरिच्छति ।

२६६१ । अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । ७ । ४ । ३४ । क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । 'बुभुक्षादौ' किम् । अशनीयति । उदकीयति धनीयति ।

२६६२ । अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । ७ । १ । ५१ । एषां क्यचि असुगागमः स्यात् । 'अश्ववृषयोर्मैथुनेच्छायाम्' (वा ४३०९) । अश्वस्यति वडवा । वृषस्यति गौः । 'क्षीरलवणयोर्लालसायाम्' (वा ४३१५) । क्षीरस्यति बालः । लवणस्यत्युष्ट्रः । 'सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ' (वा ४३१६-१७) दधिस्यति-दध्यस्यति । मधुस्यति-मध्वस्यति ।

२६६३ । काम्यच्च । ३ । १ । ९ । उक्तविषये काम्यच्स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । इह 'यस्य हलः' (सू २६३१) इति लोपो न । अनर्थकत्वात् । 'यस्य' इति संघातग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ।

२६६४ । उपमानादाचारे । ३ । १ । १० । उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच्स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् । 'अधिकरणाच्चेति वक्तव्यम्' (वा १७१७) । प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रासादे ।

२६६५ । कर्तुः क्यङ् सलोपश्च । ३ । १ । ११ । उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात्, सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्संनियोगशिष्टः । स च व्यवस्थितः । 'ओजसोऽप्सरसो नित्यमितरेषां विभाषया' (वा १७१९–२०) । कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते–यशस्यते । विद्वायते–विद्वस्यते । त्वयते । मयते । अनेकार्थत्वे तु युष्मयते । अस्मयते । 'क्यङ्मानिनोश्च' (सू ८३७) कुमारीवाचरति कुमारायते । हरिणीवाचरति हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते–सपतीयते –सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्व्याविव पट्वीमृदूयते । 'न कोपधायाः' (सू ८३८) । पाचिकायते । 'आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा' (वा १७२१) । वाग्रहणात्क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्संनियोगेनानुदात्तत्वमनुनासिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अवगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अवगल्भत इत्यादि सिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् । 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' (वा १७२२) । पूर्ववार्तिकं तु अनुबन्धासंगार्थं तत्र क्विबनूद्यते । प्रातिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । 'अतो गुणे' (सू १९१) इति शपा सह पररूपम् । अ इवाचरति अति । अतः । अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम्[1] । औ । अतुः । उः । द्वित्वम् । 'अतो गुणे' (सू १९१) 'अत आदेः' (सू २२४८) इति दीर्घः । णल् । औ । वृद्धिः । अतुसादिषु तु 'आतो लोप इटि च' (सू २३७२) इत्यालोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषयैकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालांचकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि । कवीयात् । 'सिचि वृद्धिः–' (सू २२९७) इत्यत्र 'धातोः' इत्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । माधवस्तु नामधातोरपि वृद्धिमिच्छति । अकवायीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत्–अवायीत् । श्रीरिव श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र 'गातिस्था–' (सू २२२३) इति 'भुवो वुक्–' (सू २१७४) इति 'भवतेः' (सू २१८९) इति च न भवति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । अभावीत् । बुभाव । द्रुरिव द्रवति । 'णिश्रि–' (सू २३१२) इति न चङ् । अद्रावीत् ।

२६६६ । अनुनासिकस्य क्विझलोः क्ङिति । ६ । ४ । १५ । अनुनासिकान्तस्योपधाया

---

१ 'अनेकाज्ग्रहणं चुलुम्पाद्यर्थम्' इतिवत् 'एकाज्व्यावृत्त्यर्थम्' इत्यनुनया प्रत्ययान्तैकाज्भ्योऽप्याम् भवत्येव––इति नागेशसिद्धान्तः ।

दीर्घः स्यात्क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानाति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणाति । द्यौरिव देवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । 'चकौ' इति हरदत्तः । माधवस्तु 'ण्यल्लोपौ' इति वचनाण्णालि वृद्धिं बाधित्वातो लोपाच्च क इति रूपमाह । स्व इव सस्वौ । सस्व । यत्तु स्वामास स्वांचकारेति तदनाकरमेव ।

२६६७ । भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । ३ । १ । १२ । अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्याद्धलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । 'अच्वेः' इति पर्युदासबलात् 'अभूततद्भावे' इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । 'सुमनस्' अस्य सलोपः । सुमनायते । चुरादौ 'संग्राम युद्धे' इति पठ्यते । तत्र 'संग्राम' इति प्रातिपदिकम् । तस्मात् 'तत्करोति–' इति णिच्सिद्धः । तत्संनियोगेनानुबन्ध आसज्यते । युद्धे योऽयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । 'उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इति । तेन मनःशब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं च 'आ' 'ऊढः' 'ओढः' स इवाचर्य 'ओढायित्वा' । अत्र 'उन्मनाय्य' 'अवगल्भ्य' इतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठवार्तिकं तद्भाष्यं च प्रमाणम् । तथाहि । 'उस्योमाङ्क्ष्वाटः प्रतिषेधः' (वा ३६२६) । उस्योमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छदौस्रीयत् । औङ्कारीयत् । औढीयत् । 'आटश्च' (सू २६९) इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्ठे स्थितम् ।

२६६८ । लोहितादिडाज्भ्यः क्यष् । ३ । १ । १३ । लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष्स्यात् ।

२६६९ । वा क्यषः । १ । ३ । ९० । क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति–लोहितायते । अत्र 'अच्वेः' इत्यनुवृत्त्याभूततद्भावविषयत्वं लब्धं तच्च लोहितशब्दस्यैव विशेषणम् । न तु डाचोऽसंभवात् । नाप्यादिशब्दग्राह्याणां तस्य प्रत्याख्यानात् । तथा च वार्तिकम्–'लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणि' (वा १७२९–३०) इति । न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति–पटपटायते कृभ्वस्तियोगं विनापीह डाच् । डाजन्तात्क्यषो विधानसामर्थ्यात् । यत्तु

लोहितश्यामदुःखानि हर्षगर्वसुखानि च ।
मूर्छानिद्राकृपाधूमाः करुणा नित्यचर्मणी ॥

इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति–लोहिनीयते ।

२६७० । कष्टाय क्रमणे । ३ । १ । १४ । चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ्

स्यात्। कष्टाय क्रमते कष्टायते। पापं कर्तुमुत्सहत इत्यर्थः। 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्' (वा १७३१)। कण्वं पापम्। सत्रादयो वृत्तिविषये पापार्थाः। तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ्। पापं चिकीर्षतीत्यस्वपदविग्रहः सत्रायते। कक्षायत इत्यादि।

२६७१। कर्मणो रोमन्थतपोभ्यां वर्तिचरोः। ३। १। १५। रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात्। रोमन्थं वर्तयति रोमन्थायते। 'हनुचलन इति वक्तव्यम्' (वा १७३२)। चर्वितस्याकृष्य पुनश्चर्वणमित्यर्थः। नेह। कीटो रोमन्थं वर्तयति। अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः। तदश्नातीत्यर्थ इति कैयटः। वर्तुलं करोतीत्यर्थ इति न्यासकारहरदत्तौ। 'तपसः परस्मैपदं च' (वा १७३३)। तपश्चरति तपस्यति।

२६७२। बाष्पोष्मभ्यामुद्वमने। ३। १। १६। आभ्यां कर्मभ्यां क्यङ् स्यात्। बाष्पमुद्वमति बाष्पायते। ऊष्मायते। 'फेनाच्चेति वाच्यम्' (वा १७३४)। फेनायते।

२६७३। शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे। ३। १। १७। एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात्। शब्दं करोति शब्दायते। पक्षे 'तत्करोति—' इति णिजपीष्यत इति न्यासः। शब्दयति। 'सुदिनदुर्दिननीहारेभ्यश्च' (वा १७३६–३७)। सुदिनायते।

२६७४। सुखादिभ्यः कर्तृवेदनायाम्। ३। १। १८। सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः। सुखं वेदयते सुखायते। 'कर्तृग्रहणम्' किम्। परस्य सुखं वेदयते।

२६७५। नमोवरिवश्चित्रङः क्यच्। ३। १। १९। 'करणे' इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च। नमस्यति देवान्। पूजयतीत्यर्थः। वरिवस्यति गुरून्। शुश्रूषत इत्यर्थः। चित्रीयते। विस्मयत इत्यर्थः। विस्मापयत इत्यन्ये।

२६७६। पुच्छभाण्डचीवराण्णिङ्। ३। १। २०। 'पुच्छादुदसने व्यसने पर्यसने च' (वा १७४६)। विविधं विरुद्धं वोत्क्षेपणं व्यसनम्। उत्पुच्छयते। विपुच्छयते। परिपुच्छयते। 'भाण्डात्समाचयने' (वा १७४४)। संभाण्डयते। भाण्डानि समाचिनोति। राशीकरोतीत्यर्थः। समबभाण्डत। 'चीवरादर्जने परिधाने च' (वा १७४५)। संचीवरयते भिक्षुः। चीवराण्यर्जयति परिधत्ते वेत्यर्थः।

२६७७। मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्। ३। १। २१। कृञर्थे। मुण्डं करोति मुण्डयति। 'व्रताद्भोजनतन्निवृत्त्योः' (वा ५०६०)। पयः शूद्रान्नं वा व्रतयति। '[2]वस्त्रात्समाच्छादने' (वा ५०६१)। संवस्त्रयति। '[3]हल्यादिभ्यो ग्रहणे' (वा ५०६२)। 'हलिकल्योरदन्तत्वं च निपात्यते' (वा १७४७)। हलिं कलिं वा गृह्णाति हलयति कलयति। महद्धलं हलिः। परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेऽगेव लुप्यते। अतः सन्वद्भावदीर्घौ न। अजहलत्। अचकलत्। कृतं गृह्णाति कृतयति। तूस्तानि विहन्ति वितूस्तयति। तूस्तं केशा इत्येके। जटीभूताः केशा इत्यन्ये। पापमित्यपरे। मुण्डादयः 'सत्यापपाश—' (सू २५६२) इत्यत्रैव पठितुं युक्ताः। 'प्रातिपदिकाद्धात्वर्थे—' इत्येव सिद्धे केषां-

१–३ काशिकोक्तानि.

केषांचिद्ग्रहणंसापेक्षेभ्योऽपि णिजर्थम्। मुण्डयति माणवकम्। मिश्रयत्यन्नम्। श्लक्ष्णयति वस्त्रम्। लवणयति व्यञ्जनमिति। हलिकल्योरदन्तत्वार्थम्। सत्यस्यापुगर्थम्। केषांचित्तु प्रपञ्चार्थम्। सत्यं करोत्याचष्टे वा सत्यापयति। 'अर्थवेदयोरप्यापुग्वक्तव्यः' (वा १७५८)। अर्थापयति। वेदापयति। पाशं विमुञ्चति विपाशयति। रूपं पश्यति रूपयति। वीणयोपगायत्युपवीणयति। तूलेनानुकुष्णात्यनुतूलयति। तृणाग्रं तूलेनानुघट्टयतीत्यर्थः। श्लोकैरुपस्तौति उपश्लोकयति। सेनयाभियाति अभिषेणयति। 'उपसर्गात्सुनोति–' (सू २२७०) इति षः। अभ्यषेणयत्। 'प्राक्सितात्–' (सू २२७६) इति षः। अभिषिषेणयिषति। 'स्थादिष्वभ्यासेन च–' (सू २२७७) इति षः। लोमान्यनुमार्ष्टि अनुलोमयति। 'त्वच संवरणे'। घः। त्वचं गृह्णाति त्वचयति। चर्मणा संनह्यति संचर्मयति। वर्णं गृह्णाति वर्णयति। चूर्णैरवध्वंसते अवचूर्णयति। इष्ठवदित्यतिदेशात्पुंवद्भावादयः। एनीमाचष्टे एतयति। दरदमाचष्टे दारदयति। पृथुं प्रथयति। वृद्धौ सत्यां पूर्वं वा टिलोपः। अपिप्रथत्–अपप्रथत्। मृदुं म्रदयति। अमम्रदत्। भृशं कृशं दृढं भ्रशयति क्रशयति द्रढयति। अबभ्रशत् अचक्रशत् अदद्रढत्। परिव्रढयति। पर्यवव्रढत्। ऊढिमाख्यत्। औजिढत्। ढत्वादीनामसिद्धत्वाद्धतिशब्दस्य द्वित्वम्। 'पूर्वत्रासिद्धीयमद्वित्वे' इति त्वनित्यमित्युक्तम्। 'ढि' इत्यस्य द्वित्वमित्यन्ये। औडिढत्। ऊढमाख्यत्। औजढत्–औडढत्। 'ओः पुयण्–' (सू २५७७) इति वर्गप्रत्याहारजग्रहो लिङ्गम्। 'द्वित्वे कार्ये णावच आदेशो न' इति ऊनयतावुक्तम्। 'प्रकृत्यैकाच्' (सू २०१०)। वृद्धिपुकौ। स्वापयति। त्वां मां वाचष्टे त्वापयति मापयति। मपर्यन्तस्य त्वमौ। पररूपात्पूर्वं नित्यत्वाट्टिलोपः। वृद्धिः पुक्। त्वादयति मादयतीति तु न्याय्यम्। अन्तरङ्गत्वात्पररूपे कृते 'प्रकृत्यैकाच्' (सू २०१०) इति प्रकृतिभावात्। न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम्। भाष्यस्य प्रेष्ठाद्युदाहरणविशेषेऽन्यथासिद्धिपरत्वात्। युवामावां वा युष्मयति। अस्मयति। श्वानमाचष्टे शावयति। 'नस्तद्धिते' (सू ६७९) इति टिलोपः। प्रकृतिभावस्तु न येन नाप्राप्तिन्यायेन 'टेः' (सू १७८६) इत्यस्यैव बाधको हि सः। भत्वात्संप्रसारणम्। अन्ये तु 'नस्तद्धिते' (सू ६७९) इति नेहातिदिश्यते इष्ठनि तस्यादृष्टत्वात्। स्रजिष्ठ इत्यादौ परत्वात् 'टेः' (सू १७८६) इत्यस्यैव प्रवृत्तेः। तेन शुनयतीति रूपमाहुः। विद्वांसमाचष्टे विद्वयति। अङ्गवृत्तपरिभाषया संप्रसारणं नेत्येके। संप्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये। नित्यत्वाट्टिलोपात्प्राक्संप्रसारणम्। अन्तरङ्गत्वात्पूर्वरूपं टिलोपः। विदयतीत्यपरे। उदञ्चमाचष्टे उदीचयति। उदैचिचत्। प्रत्यञ्चं प्रतीचयति। प्रत्यचिचत्। 'इकोऽसवर्णे–' (सू ९१) इति प्रकृतिभावपक्षे। प्रतिअचिचत्। सम्यञ्चमाचष्टे समीचयति। सम्यचिचत्–समिअचिचत्। तिर्यञ्चमाचष्टे तिराययति। अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः। 'असिद्धवदत्र–' (सू २१८३) इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः। अतः पुनष्टिलोपो न। अङ्गवृत्तपरिभाषया वा। चङ्यग्लोपित्वादुपधाह्रस्वो न। अतितिरायत्। सध्र्यञ्चमाचष्टे सध्राययति। अससध्रायत्। विष्वग्र्यञ्चम् अविविष्वद्रायत्। देवद्र्यञ्चम् अदिदेवद्रायत्। अदद्र्यञ्चम् आददद्रायत्। अदमुयञ्चम् अदमुआययति। आददमुआयत्। अमुमुयञ्चम् अमुमुआययति। चङ्। आमुमुआयत्। भुवं भावयति। अबीभवत्। भ्रुवम् अबुभ्रवत्। श्रियम् अशिश्रयत्। गाम् अजूगवत्। रायम् अरीरयत्। नावम्

अनूनवत् । स्वश्वम् स्वाशश्वत् । स्वः । अव्ययानां भमात्रे टिलोपः । स्वयति । असस्वत्-असिस्वत् । बहूनभावयति । बहयतीत्यन्ये । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा । श्रययति । अशिश्रयत् । पयस्विनीम् पयसयति । इह टिलोपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलम् स्थवयति । दूरम् दवयति । कथं तर्हि 'दूरयत्यवनते विवस्वति' इति । दूरमतति अयते वा दूरात् । दूरातं कुर्वतीत्यर्थः । युवानं यवयति । कनयति । 'युवाल्पयोः-' (सू २०१९) इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्यति । इह श्रज्यौ न उपसर्गस्य पृथक्कृतेः । वृद्धम् ज्यापयति । वर्षयति । प्रियम् प्रापयति । स्थिरम् स्थापयति । स्फिरम् स्फापयति । उरुम् वरयति । वारयति । बहुलम् बंहयति । गुरुम् गरयति । तृप्रम् त्रपयति । दीर्घम् द्राघयति । वृन्दारकम् वृन्दयति ।

इति तिङन्तनामधातुप्रकरणम् ।

अथ तिङन्तकण्ड्वादिप्रकरणम् ।

२६७८ । कण्ड्वादिभ्यो यक् । ३ । १ । २७ । एभ्यो धातुभ्यो नित्यं यक्स्यात्स्वार्थे । 'धातुभ्यः' किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः, धातवः प्रातिपदिकानि च । 'कण्डूञ् गात्रविघर्षणे' । कण्डूयति-कण्डूयते । 'मन्तु अपराधे' । रोष इत्येके । मन्तूयति । चन्द्रस्तु जितमाह । मन्तूयते । 'वल्गु पूजामाधुर्ययोः' । वल्गूयति । 'असु उपतापे' । 'असु' 'असूञ्' इत्येके । अस्यति । असूयति-असूयते । 'लेट् लोट् धौर्त्ये पूर्वभावे स्वप्ने च' । दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता । 'लेला दीप्तौ' । 'इरस् इरज् इरञ् ईर्ष्यायाम्' । इरस्यति । इरज्यति । 'हलि च' (सू ३५४) इति दीर्घः । ईर्यति-ईर्यते । 'उषस् प्रभातीभावे' । 'वेद धौर्त्ये स्वप्ने च' । 'मेधा आशुग्रहणे' । मेधायति । 'कुषुभ क्षेपे' । कुषुभ्यति । 'मगध परिवेष्टने' । 'नीच दास्ये' इत्यन्ये । 'तन्तस् पम्पस् दुःखे' । 'सुख दुःख तत्क्रियायाम्' । सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । 'सपर पूजायाम्' । 'अरर आराकर्मणि' । 'भिषज् चिकित्सायाम्' । 'भिष्णज् उपसेवायाम्' । 'इषुध शरधारणे' । 'चरण वरण गतौ' । 'चुरण चौर्ये' । 'तुरण त्वरायाम्' । 'भुरण धारणपोषणयोः' । 'गद्गद वाक्स्खलने' । 'एला केला खेला विलासे' । 'इल इत्यन्ये' । 'लेखा स्खलने च' । अदन्तोऽयमित्यन्ये । लेख्यति । 'लिट अल्पकुत्सनयोः' । लिट्यति । 'लाट जीवने' । 'हृणीङ् रोषणे लज्जायां च' । 'महीङ् पूजायाम्' । महीयते । पूजां लभत इत्यर्थः । 'रेखा श्लाघासादनयोः' । 'द्रवस् परितापपरिचरणयोः' । 'तिरस् अन्तर्धौ' । 'अगद नीरोगत्वे' । 'उरस् बलार्थः' । उरस्यति । बलवान्भवतीत्यर्थः । 'तरण गतौ' । 'पयस प्रसृतौ' । 'संभूयस् प्रभूतभावे' । 'अम्बर संवर संभरणे' । आकृतिगणोऽयम् ।

इति तिङन्तकण्ड्वादिप्रकरणम् ।

अथ तिङन्तप्रत्ययमालाप्रकरणम् ।

कण्डूयतेः सन् । 'सन्यङोः' (सू २३९९) इति प्रथमस्यैकाचो द्वित्वे प्राप्ते । 'कण्ड्वादेस्तृतीयस्येति वाच्यम्' (वा ३४०४) । कण्डूयियिषति । क्यजन्तात्सन् । 'यथेष्टं नामधातुषु (वा ३४०६) । आद्यानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः । अजादेस्त्वाद्येतरस्य । पुत्रीयियिषति-पुतित्रीयिषति-पुत्रीयियिषति । अशिश्वीयिषति-अश्वीयियिषति । नदराणां संयुक्तानामचः परस्यैव द्वित्वनिषेधः । इन्द्रीयतेः सन् । द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् । इन्दिद्रीयिषति-इन्द्रीयियिषति । चिचन्द्रीयिषति-चान्दिद्रीयिषति-चन्द्रीयियिषति-प्रियमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छति । पिप्रापयिषति-प्रापिपयिषति-प्रापयियिषति । उरुं विवारयिषति-वारिरयिषति-वारयियिषति । वादं सिसाधयिषतीत्यादिरूपत्रयम् । षत्वं तु नास्ति । 'यङ्सनूण्यन्तात्सन्' । बोभूयिषयिषति । यङ्णिच्सन्नन्ताण्णिच् । बोभूययिषतीत्यादि ।

इति तिङन्तप्रत्ययमालाप्रकरणम् ।

अथ तिङन्तात्मनेपदप्रकरणम् ।

'अनुदात्तङित आत्मनेपदम्' (सू २१५७) । आस्ते । शेते ।

२६७९ । भावकर्मणोः । १ । ३ । १३ । बभूवे । अनुबभूवे ।

२६८० । कर्तरि कर्मव्यतिहारे । १ । ३ । १४ । क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः । 'श्नसोरल्लोपः' (सू २४६९) । व्यतिस्ते । व्यतिषाते । व्यतिषते । 'तासस्त्योः-' (सू २१९१) इति सलोपः । व्यतिसे । 'धि च' (सू २२४९) । व्यतिध्वे । 'ह एति' (सू २२५०) । व्यतिहे । व्यत्यसै । व्यतिषीत । व्यत्यास्त । व्यतिराते । व्यतिराते । व्यतिराते व्यतिभाते । व्यतिभाते । व्यतिभाते । व्यतिबभे ।

२६८१ । न गतिहिंसार्थेभ्यः । १ । ३ । १५ । व्यतिगच्छन्ति । व्यतिघ्नन्ति । 'प्रतिषेधे हसादीनामुपसंख्यानम्' (वा ८९८) हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति । 'हरतेरप्रतिषेधः' (वा ८९९) । संप्रहरन्ते राजानः ।

२६८२ । इतरेतरान्योन्योपपदाच्च । १ । ३ । १६ । 'परस्परोपपदाच्चेति वक्तव्यम्' (वा ९००) । इतरेतरस्यान्योऽन्यस्य परस्परस्य वा व्यतिलुनन्ति ।

२६८३ । नेर्विशः । १ । ३ । १७ । निविशते ।

२६८४ । परिव्यवेभ्यः क्रियः । १ । ३ । १८ । अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते-विक्रीणीते-अवक्रीणीते ।

२६८५ । विपराभ्यां जेः । १ । ३ । १९ । विजयते । पराजयते ।

२६८६ । आङो दोऽनास्यविहरणे । १ । ३ । २० । आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् । विद्यामादत्ते । 'अनास्य-' इति किम् । मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । 'पादस्फोटो विपादिका' । नदी कूलं व्याददाति । 'पराङ्गकर्मकान्न निषेधः' (वा ९०३) । व्याददते पिपीलिकाः पतङ्गस्य मुखम् ।

२६८७ । क्रीडोऽनुसंपरिभ्यश्च । १ । ३ । २१ । चादाङः । अनुक्रीडते । संक्रीडते ।

परिक्रीडते। आक्रीडते। अनोः कर्मप्रवचनीयान्न। उपसर्गेण समा साहचर्यात्। माणवकमनुक्रीडति। तेन सहेत्यर्थः। 'तृतीयार्थे' (सू ५४९) इत्यनोः कर्मप्रवचनीयत्वम्। 'समोऽकूजने' (वा ९०४)। संक्रीडते। कूजने तु। संक्रीडति चक्रम्। 'आगमेः क्षमायाम्' (वा ९०५)। ण्यन्तस्येदं ग्रहणम्। आगमयस्व तावत्। मा त्वरिष्ठा इत्यर्थः। 'शिक्षेर्जिज्ञासायाम्' (वा ९०६)। धनुषि शिक्षते। धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः। 'आशिषि नाथः' (वा ९१०)। आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम्। सर्पिषो नाथते। सर्पिर्मे स्यादित्याशास्त इत्यर्थः। कथं 'नाथसे किमु पतिं न भूभृताम्' इति। 'नाधसे' इति पाठ्यम्। 'हरतेर्गतताच्छील्ये' (वा ९०८)। गतं प्रकारः। पैतृकमश्वा अनुहरन्ते। मातृकं गावः। पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः। 'ताच्छील्ये' किम्। मातुरनुहरति। 'किरतेर्हर्षजीविकुलायकरणेष्विति वाच्यम्' (वा ९०७)। हर्षादयो विषयाः। तत्र हर्षो विक्षेपस्य कारणम्। इतरे फले।

२६८८। अपाच्चतुष्पाच्छकुनिष्वालेखने। ६। १। १४२। अपात्किरतेः सुट् स्यात्। 'सुडपि हर्षादिष्वेव वक्तव्यः' (वा ३७०६)। अपस्किरते वृषो हृष्टः। कुक्कुटो भक्षार्थी। श्वा आश्रयार्थी च। 'हर्षादिषु' इति किम्। अपकिरति कुसुमम्। इह तङ्सुटौ न। हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि 'सुडभावे नेष्यते' इत्याहुः। गजोऽपकिरति। 'आङि नुप्रच्छ्योः' (वा ९०९)। आनुते। आपृच्छते। 'शप उपालम्भे' (वा ९११)। आक्रोशार्थात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः। कृष्णाय शपते।

२६८९। समवप्रविभ्यः स्थः। १। ३। २२। संतिष्ठते। 'स्थाघ्वोरिच' (सू २३८९)। समस्थित। समस्थिषाताम्। समस्थिषत। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते। 'आङः प्रतिज्ञायामुपसंख्यानम्' (वा ९१२)। शब्दं नित्यमातिष्ठते। नित्यत्वेन प्रतिजानीत इत्यर्थः।

२६९०। प्रकाशनस्थेयाख्ययोश्च। १। ३। २३। गोपी कृष्णाय तिष्ठते। आशयं प्रकाशयतीत्यर्थः। 'संशय्य कर्णादिषु तिष्ठते यः'। कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः।

२६९१। उदोऽनूर्ध्वकर्मणि। १। ३। २४। मुक्तावुत्तिष्ठते। 'अनूर्ध्व–' इति किम्। पीठादुत्तिष्ठति। 'ईहायामेव' (वा९१३)। नेह। ग्रामाच्छतमुत्तिष्ठति।

२६९२। उपान्मन्त्रकरणे। १। ३। २५। आग्नेय्याग्नीध्रमुपतिष्ठते। 'मन्त्रकरणे' किम्। 'भर्तारमुपतिष्ठति यौवनेन'। 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्' (वा ९१४)। आदित्यमुपतिष्ठते। कथं तर्हि 'स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती' इति। देवतात्वारोपात्। नृपस्य देवतांशत्वाद्वा। गङ्गा यमुनामुपतिष्ठते। उपश्लिष्यतीत्यर्थः। रथिकानुपतिष्ठते। मित्री करोतीत्यर्थः। पन्थाः स्रुघ्नमुपतिष्ठते। प्राप्नोतीत्यर्थः। 'वा लिप्सायामिति वक्तव्यम्' (वा ९१९)। भिक्षुकः प्रभुमुपतिष्ठते–उपतिष्ठति वा। लिप्सया उपगच्छतीत्यर्थः।

२६९३। अकर्मकाच्च। १। ३। २६। उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात्। भोजनकाल उपतिष्ठते। संनिहितो भवतीत्यर्थः।

२६९४। उद्विभ्यां तपः। १। ३। २७। 'अकर्मकात्' इत्येव। उत्तपते। वितपते।

दीप्यत इत्यर्थः । 'स्वाङ्गकर्मकाच्चेति वक्तव्यम्' (वा ९१६) । स्वमङ्गं स्वाङ्गं न तु 'अद्रवम्–' इति परिभाषितम् । उत्तपते । वितपते पाणिम् । नेह । सुवर्णमुत्तपति । संतापयति-विलापयति वेत्यर्थः । चैत्रो मैत्रस्य पाणिमुत्तपति । संतापयतीत्यर्थः ।

२६९५ । आङो यमहनः । १ । ३ । २८ । आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह । परस्य शिर आहन्ति । कथं तर्हि 'आजघ्ने विषमविलोचनस्य वक्षः' इति भारविः । 'आहध्वं मा रघूत्तमम्' इति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वास्तु । समीपमेत्येति वा ।

२६९६ । आत्मनेपदेष्वन्यतरस्याम् । २ । ४ । ४४ । हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । आवधिष्ट । आवधिषाताम् ।

२६९७ । हनः सिच् । १ । २ । १४ । कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ।

२६९८ । यमो गन्धने । १ । २ । १५ । सिच्कित्स्यात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । 'गन्धने' किम् । उदायंस्त पादम् । आकृष्टवानित्यर्थः ।

२६९९ । समो गम्यृच्छिभ्याम् । १ । ३ । २९ । 'अकर्मकाभ्याम्' इत्येव । संगच्छते ।

२७०० । वा गमः । १ । २ । १३ । गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्ट-संगंसीष्ट । समगत-समगंस्त । समृच्छिष्यते । 'अकर्मकाभ्याम्' किम् । ग्रामं संगच्छति । 'विदिप्रच्छिस्वरतीनामुपसंख्यानम्' (वा ९१८) । वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ।

२७०१ । वेत्तेर्विभाषा । ७ । १ । ७ । वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संपृच्छते । संस्वरते । 'अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम्' (वा ९२६) । अर्तीति द्वयोर्ग्रहणम् । अङ्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु मा समरत । मा समरेताम् । मा समरन्त । समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव 'रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा 'इति कथयद्भ्यः' इति । अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ।

धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।

प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥

वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । 'हितान्न यः संशृणुते स किं प्रभुः' । 'उपसर्गादस्यत्यूह्योर्वेति वाच्यम्' (वा ९२०) । 'अकर्मकात्' इति निवृत्तम् । बन्धं निरस्यति-निरस्यते । समूहति-समूहते ।

२७०२ । उपसर्गाद्ध्रस्व ऊहतेः । ७ । ४ । २३ । यादौ क्ङिति । ब्रह्म समुह्यात् । अग्निं समुह्य ।

२७०३। निसमुपविभ्यो ह्वः। १। ३। ३०। निह्वयते।

२७०४। स्पर्धायामाङः। १। ३। ३१। कृष्णश्चाणूरमाह्वयते। 'स्पर्धायाम्' किम्। पुत्रमाह्वयति।

२७०५। गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः। १। ३। ३२। गन्धनं हिंसा। उत्कुरुते। सूचयतीत्यर्थः। सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुदाकुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवते। परदारान्प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। गाथाः प्रकुरुते। प्रकथयति। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। 'एषु' किम्। कटं करोति।

२७०६। अधेः प्रसहने। १। ३। ३३। प्रसहनं क्षमाभिभवश्च। 'षह मर्षणेऽभिभवे च' इति पाठात्। शत्रुमधिकुरुते। क्षमत इत्यर्थः। अभिभवतीति वा।

२७०७। वेः शब्दकर्मणः। १। ३। ३४। स्वरान्विकुरुते। उच्चारयतीत्यर्थः। 'शब्दकर्मणः' किम्। चित्तं विकरोति कामः।

२७०८। अकर्मकाच्च। १। ३। ३५। 'वेः कृञः' इत्येव। छात्रा विकुर्वते। विकारं लभन्ते।

२७०९। संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः। १। ३। ३६। अत्रोत्संजनज्ञानविगणनव्यया नयतेर्वाच्याः। इतरे प्रयोगोपाधयः। तथा हि। शास्त्रे नयते। शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः। तेन च शिष्यसंमाननं फलितम्। उत्संजने। दण्डमुन्नयते। उत्क्षिपतीत्यर्थः। माणवकमुपनयते। विधिनात्मसमीपं प्रापयतीत्यर्थः। उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते। ज्ञाने। तत्त्वं नयते। निश्चिनोतीत्यर्थः। कर्मकरानुपनयते। भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः। विगणनमृणादेर्निर्यातनम्। करं विनयते। राज्ञे देयं भागं परिशोधयतीत्यर्थः। शतं विनयते। धर्मार्थं विनियुङ्क्त इत्यर्थः।

२७१०। कर्तृस्थे चाशरीरे कर्मणि। १। ३। ३७। नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्न एव स्यात्। सूत्रे शरीरशब्देन तदवयवो लक्ष्यते। क्रोधं विनयते। अपगमयति। तत्फलस्य चित्तप्रसादस्य कर्तृगत्वात् 'स्वरितञितः–' (सू २१५८) इत्येव सिद्धे नियमार्थमिदम्। तेनेह न। गडुं विनयति। कथं तर्हि 'विगणय्य नयन्ति पौरुषम्' इति। कर्तृगामित्वाविवक्षायां भविष्यति।

२७११। वृत्तिसर्गतायनेषु क्रमः। १। ३। ३८। वृत्तिरप्रतिबन्धः। ऋचि क्रमते बुद्धिः। न प्रतिहन्यत इत्यर्थः। सर्ग उत्साहः। अध्ययनाय क्रमते। उत्सहते। क्रमन्तेऽस्मिन् शास्त्राणि। स्फीतानि भवन्तीत्यर्थः।

२७१२। उपपराभ्याम्। १। ३। ३९। वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात्। उपक्रमते। पराक्रमते। नेह संक्रामति।

२७१३। आङ उद्गमने। १। ३। ४०। आक्रमते सूर्यः। उदयत इत्यर्थः। 'ज्योतिरुद्गमन इति वाच्यम्' (वा ९२१)। नेह। आक्रामति धूमो हर्म्यतलात्।

२७१४ । वेः पादविहरणे । १ । ३ । ४१ । साधु विक्रमते वाजी । 'पादविहरणे' किम् । विक्रामति संधिः । द्विधा भवति । स्फुटतीत्यर्थः ।

२७१५ । प्रोपाभ्यां समर्थाभ्याम् । १ । ३ । ४२ । समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । 'समर्थाभ्याम्' किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ।

२७१६ । अनुपसर्गाद्वा । १ । ३ । ४३ । क्रामति-क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ।

२७१७ । अपह्नवे ज्ञः । १ । ३ । ४४ । शतमपजानीते । अपलपतीत्यर्थः ।

२७१८ । अकर्मकाच्च । १ । ३ । ४५ । सर्पिषो जानीते । सर्पिषा उपायेन प्रवर्तत इत्यर्थः ।

२७१९ । संप्रतिभ्यामनाध्याने । १ । ३ । ४६ । शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । 'अनाध्याने' इति योगो विभज्यते । तत्सामर्थ्यात् 'अकर्मकाच्च' (सू २७१८) इति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ।

२७२० । भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । १ । ३ । ४७ । उपासंभाषोपमन्त्रणे धात्वर्थौ, इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते प्रार्थयत इत्यर्थः ।

२७२१ । व्यक्तवाचां समुच्चारणे । १ । ३ । ४८ । मनुष्यादीनां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह संप्रवदन्ति खगाः ।

२७२२ । अनोरकर्मकात् । १ । ३ । ४९ । व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । 'अकर्मकात्' किम् । उक्तमनुवदति । 'व्यक्तवाचाम्' किम् । अनुवदति वीणा ।

२७२३ । विभाषा विप्रलापे । १ । ३ । ५० । विरुद्धोक्तिरूपे व्यक्तवाचां समुच्चारण उक्तं वा स्यात् । विप्रवदन्ते-विप्रवदन्ति वा वैद्याः ।

२७२४ । अवाद्ग्रः । १ । ३ । ५१ । अवगिरते । 'गृणातिस्त्ववपूर्वो न प्रयुज्यत एव' इति भाष्यम् ।

२७२५ । समः प्रतिज्ञाने । १ । ३ । ५२ । शब्दं नित्यं संगिरन्ते । प्रतिजानीत इत्यर्थः । 'प्रतिज्ञाने' किम् । संगिरति ग्रासम् ।

२७२६ । उदश्चरः सकर्मकात् । १ । ३ । ५३ । धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः 'सकर्मकात्' किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ।

२७२७ । समस्तृतीयायुक्तात् । १ । ३ । ५४ । रथेन संचरते ।

२७२८ । दाणश्च सा चेच्चतुर्थ्यर्थे । १ । ३ । ५५ । संपूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं

स्यात् तृतीया चेच्चतुर्थ्यर्थे। दास्या संयच्छते। पूर्वसूत्रे 'समः' इति षष्ठी। तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते। रथेन समुदाचरते। दास्या संप्रयच्छते।

२७२९। उपाद्यमः स्वकरणे। १। ३। ५६। स्वकरणं स्वीकारः। भार्यामुपयच्छते।

२७३०। विभाषोपयमने। १। २। १६। यमः सिच्कित्वा स्याद्विवाहे। रामः सीतामुपायत—उपायंस्त वा। उदवोढेत्यर्थः। गन्धनाङ्ग उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम्।

२७३१। ज्ञाश्रुस्मृदृशां सनः। १। ३। ५७। सन्नन्तानामेषां प्राग्वत्। धर्मं जिज्ञासते। शुश्रूषते। सुस्मूर्षते। दिदृक्षते।

२७३२। नानोर्ज्ञः। १। ३। ५८। पुत्रमनुजिज्ञासति। पूर्वसूत्रस्यैवायं निषेधः। 'अनन्तरस्य—'(प ६२) इति न्यायात् तेनेह न। सर्पिषोऽनुजिज्ञासते। सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः। 'पूर्ववत्सनः' (सू २७३४) इति तङ्। 'अकर्मकाच्च' (सू २७१८) इति केवलाद्विधानात्।

२७३३। प्रत्याङ्भ्यां श्रुवः। १। ३। ५९। आभ्यां सन्नन्ताच्छ्रुव उक्तं न स्यात्। प्रतिशुश्रूषति। आशुश्रूषति। कर्मप्रवचनीयात्स्यादेव। देवदत्तं प्रति शुश्रूषते। 'शदेः शितः' (सू २३६२) 'म्रियतेर्लुङ्लिङोश्च' (सू २५३८) व्याख्यातम्।

२७३४। पूर्ववत्सनः। १। ३। ६२। सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिषते। शिशयिषते। निविविक्षते। 'पूर्ववत्' किम्। बुभूषति। 'शदेः—' (सू २३६२) (सू २५३८) इत्यादिसूत्रद्वये 'सनो न' इत्यनुवर्त्य वाक्यभेदेन व्याख्येयम्। तेनेह न। शिशत्सति। मुमूर्षति। 'आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य' (सू २२४०)। एधांचक्रे।

२७३५। प्रोपाभ्यां युजेरयज्ञपात्रेषु। १। ३। ६४। प्रयुङ्क्ते। उपयुङ्क्ते। 'स्वराद्यन्तोपसर्गादिति वक्तव्यम्' (वा ९३९)। उद्युङ्क्ते। नियुङ्क्ते। 'अयज्ञपात्रेषु' किम्। द्वन्द्वं न्युब्जपात्राणि प्रयुनक्ति।

२७३६। समः क्ष्णुवः। १। ३। ६५। संक्ष्णुते शस्त्रम्।

२७३७। भुजोऽनवने। १। ३। ६६। ओदनं भुङ्क्ते। अभ्यवहरतीत्यर्थः। 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्'। 'वृद्धो जनो दुःखशतानि भुङ्क्ते'। इहोपभोगो भुजेरर्थः। 'अनवने' किम्। महीं भुनक्ति।

२७३८। णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने। १। ३। ६७। ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेण्ण्यन्तेनोच्यते अणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादनाध्याने। 'णिचश्च' (सू २५६४) इति सिद्धेऽकर्त्रभिप्रायार्थमिदम्। कर्त्रभिप्राये तु 'विभाषोपपदेन—' (सू २७४४) इति विकल्पे 'अणावकर्मकात्—' (सू २७५४) इति परस्मैपदे च प्राप्ते 'पूर्वविप्रतिषेधेनेदमेवेष्यते। कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम्। तथा हि। पश्यन्ति भवं भक्ताः। चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः। प्रेरणांशत्यागे। पश्यति भवः। विषयो भवतीत्यर्थः। ततो हेतुमण्णिच्। दर्शयन्ति भवं भक्ताः। पश्यन्तीत्यर्थः। पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः। इह प्रथमतृतीययोरवस्थयोर्द्वितीयचतुर्थ्योश्च तुल्योऽर्थः। तत्र तृतीयकक्षायां न तङ्। क्रियासाम्येऽप्यणौ कर्मकारकस्य णौ कर्तृत्वाभावात्। चतुर्थ्यां तु तङ्। द्वितीयामादाय क्रियासाम्यात्। प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च। एवमारोहयते हस्तीत्यप्युदाहरणम्। आरोहन्ति हस्तिनं हस्तिपकाः। न्यग्भावयन्तीत्यर्थः। तत आरो-

हति हस्ती । न्यग्भवतीत्यर्थः । ततो णिजारोहयन्ति । आरोहन्तीत्यर्थः । तत आरोहयते । न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्षा प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाण्णिच् । दर्शयति भवः । आरोहयति हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोर्द्वयोरपि प्रेषणयोस्त्यागे दर्शयत आरोहयत इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षे द्वितीयकक्षायां न तङ् । समानक्रियत्वाभावाण्णिजर्थस्याधिक्यात् । अनाध्याने' किम् । स्मरति वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । 'भीस्म्योर्हेतुभये' (सू २५९४) व्याख्यातम् ।

२७३९ । गृधिवञ्च्योः प्रलम्भने । १ । ३ । ६९ । प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते । वञ्चयते वा । 'प्रलम्भने' किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । 'लियः संमाननशालीनीकरणयोश्च' (सू २५९२) । व्याख्यातम् ।

२७४० । मिथ्योपपदात्कृञोऽभ्यासे । १ । ३ । ७१ । 'णेः' इत्येव । पदं मिथ्याकारयते । स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । 'मिथ्योपपदात्' किम् । पदं सुष्ठु कारयति । 'अभ्यासे' किम् । सकृत्पदं मिथ्या कारयति । 'स्वरितञितः कर्त्रभिप्राये क्रियाफले' (सू २१५८) । यजते । सुनुते । 'कर्त्रभिप्राये' किम् । ऋत्विजो यजन्ति । सुन्वन्ति ।

२७४१ । अपाद्वदः । १ । ३ । ७३ । न्यायमपवदते । कर्त्रभिप्राय इत्येव । अपवदति । 'णिचश्च' (सू २५६४) । कारयते ।

२७४२ । समुदाङ्भ्यो यमोऽग्रन्थे । १ । ३ । ७५ । 'अग्रन्थे' इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । 'अग्रन्थे' किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राय इत्येव ।

२७४३ । अनुपसर्गाज्ज्ञः । १ । ३ । ७६ । गां जानीते । 'अनुपसर्गात्' किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः-'इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य' इति । कर्मणि लिट् । नृपेनेति विपरिणामः ।

२७४४ । विभाषोपपदेन प्रतीयमाने । १ । ३ । ७७ । स्वरितञित इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । स्वं यज्ञं यजति-यजते वा । स्वं कटं करोति-कुरुते वा । स्वं पुत्रमपवदति-अपवदते वा । स्वं यज्ञं कारयति-कारयते वा । स्वं व्रीहिं संयच्छति-संयच्छते वा । स्वां गां जानाति-जानीते वा ।

इति तिङन्तात्मनेपदप्रकरणम् ।

अथ तिङन्तपरस्मैपदप्रकरणम् ।

'शेषात्कर्तरि परस्मैपदम्' (सू २१५९) अस्ति ।

२७४५ । अनुपराभ्यां कृञः । १ । ३ । ७९ । कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र 'कर्मवत्कर्मणा-' (सू २७६६)

इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु 'कर्तरि शप्' (सू २१६७) इत्यतः 'शेषात्–' (सू २१५९) इत्यतश्च कर्तृग्रहणद्वयमनुवर्त्य कर्तैव यः कर्ता न तु कर्मकर्ता तत्रेति व्याख्येयम् ।

२७४६ । अभिप्रत्यतिभ्यः क्षिपः । १ । ३ । ८० । 'क्षिप प्रेरणे' । स्वरितेत् । अभिक्षिपति ।

२७४७ । प्राद्वहः । १ । ३ । ८१ । प्रवहति ।

२७४८ । परेर्मृषः । १ । ३ । ८२ । परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ।

२७४९ । व्याङ्परिभ्यो रमः । १ । ३ । ८३ । विरमति ।

२७५० । उपाच्च । १ । ३ । ८४ । यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ।

२७५१ । विभाषाकर्मकात् । १ । ३ । ८५ । उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति–उपरमते वा । निवर्तत इत्यर्थः ।

२७५२ । बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः । १ । ३ । ८६ । एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । 'णिचश्च' (सू २५६४) इत्यस्यापवादः । योधयति पद्मम् । बोधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्त्रावयति । स्यन्दयतीत्यर्थः ।

२७५३ । निगरणचलनार्थेभ्यश्च । १ । ३ । ८७ । निगारयति । आशयति । भोजयति । चलयति । कम्पयति । 'अदेः प्रतिषेधः' (वा ९९९) । आदयते देवदत्तेन । 'गतिबुद्धि–' (सू ५४०) इति कर्मत्वम् 'आदिखाद्योर्न' (वा ११०९) इति प्रतिषिद्धम् । 'निगरणचलन–' (सू २७५३) इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषादित्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ।

२७५४ । अणावकर्मकाच्चित्तवत्कर्तृकात् । १ । ३ । ८८ । ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ।

२७५५ । न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः । १ । ३ । ८९ । एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृकाकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते । 'धेट उपसंख्यानम्' (वा ९६२) 'धापयेते शिशुमेकं समीची' । अकर्त्रभिप्राये 'शेषात्–' (सू २१५९) इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । 'दमयन्तीकमनीयतामदम्' । भिक्षां वासयति । 'वा क्यषः' (सू २६६९) लोहितायति–लोहितायते । 'द्युद्भ्यो लुङि' (सू २३४५) । अद्युतत्–अद्योतिष्ट । 'वृद्भ्यः स्यसनोः' (सू २३४७) वर्त्स्यति । वर्तिष्यते । विवृत्सति । विवर्तिषते । 'लुटि च कॢपः' (सू २३५१) । कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्स्यति कल्पिष्यते–कल्प्स्यते । चिक्ळृप्सति–चिकल्पिषते–चिक्लृप्सते ।

इति तिङन्तपरस्मैपदप्रकरणम् ।

अथ भावकर्मतिङ्प्रकरणम्।

अथ भावकर्मणोर्लडादयः। 'भावकर्मणोः' (सू २६७९) इति तङ्।

२७५६। सार्वधातुके यक्।३।१।६७। धातोर्यक्प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे। भावो भावना उत्पादना क्रिया। सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते। युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमपुरुषः तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि। किं त्वेकवचनमेव। तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वादनभिहिते कर्तरि तृतीया। त्वया मयान्यैश्च भूयते। बभूवे।

२७५७। स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च।६।४।६२। उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। अयमिट् चिण्वद्भावसंनियोगशिष्टत्वात्तदभावे न इहार्धधातुक इत्यधिकृतं स्यादीनां विशेषणं, नेतरेषामव्यभिचारात्। चिण्वद्भावाद्वृद्धिः। भाविता–भविता। भाविष्यते–भविष्यते। भूयताम्। अभूयत। भूयेत। भाविषीष्ट–भविषीष्ट।

२७५८। चिण्भावकर्मणोः।३।१।६६। च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे। अभावि। अभाविष्यत–अभविष्यत। तिङ्क्तत्वात्कर्मणि न द्वितीया। अनुभूयत आनन्दश्चैत्रेण त्वया मया च। अनुभूयेते। अनुभूयन्ते। त्वमनुभूयसे। अहमनुभूये। अन्वभावि। अन्वभाविषाताम्–अन्वभविषाताम्। णिलोपः। भाव्यते। भावयांचक्रे। भावयांबभूवे। भावयामासे। इहतशब्दस्य एशि, इट एत्त्वे च, कृते 'ह एति' (सू २२५०) इति हत्वं न। तासिसाहचर्यादस्तेरपि व्यतिह इत्यादौ सार्वधातुक एति हत्वप्रवृत्तेरित्याहुः। भाविता। चिण्वदिट आभीयत्वेनासिद्धत्वाण्णिलोपः। पक्षे। भावयिता। भाविष्यते–भावयिष्यते। भाव्यताम्। अभाव्यत। भाव्येत। भाविषीष्ट–भावयिषीष्ट। अभावि। अभाविषाताम्। अभावयिषाताम्। बुभूष्यते। बुभूषांचक्रे। बुभूषिता। बुभूषिष्यते। बोभूय्यते। यङ्लुगन्तात्तु। बोभूयते। बोभवांचक्रे। बोभाविता–बोभविता। 'अकृत्सार्व–' (सू २२९८) इति दीर्घः। स्तूयते विष्णुः। तुष्टुवे। स्ताविता–स्तोता। स्ताविष्यते–स्तोष्यते। अस्तावि। अस्ताविषाताम्–अस्तोषाताम्। 'गुणोऽर्तिऽ' (सू २३८०) इति गुणः। अर्यते। स्मर्यते। सस्मरे। परत्वान्नित्यत्वाच्च गुणे रपरे कृतेऽजन्तत्वाभावेऽप्युपदेशग्रहणाच्चिण्वदिट्। आरिता–अर्ता। स्मारिता–स्मर्ता। 'गुणोऽर्ति–' (सू २३८०) इत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः। संस्क्रियते। 'अनिदिताम्–' (सू ४१५) इति नलोपः। स्रस्यते। इदितस्तु नन्द्यते। संप्रसारणम्। इज्यते। 'अयङ्यि क्ङिति' (सू २६४९)। शय्यते।

२७५९। तनोतेर्यकि।६।४।४४। आकारोऽन्तादेशो वा स्यात्। तायते–तन्यते। 'ये विभाषा' (सू २३१९)। जायते–जन्यते।

२७६०। तपोऽनुतापे च।३।१।६५। तपश्च्लेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च। अन्वतप्त पापेन। पापं कर्तृ तेनाभ्याहत इत्यर्थः। कर्मणि लुङ्। यद्वा पापेन पुंसा कर्त्रा अशोचीत्यर्थः। 'घुमास्था–' (सू २४६२) इतीत्वम्। दीयते। धीयते। 'आदेचः–'

(सू २३७०) इत्यत्राशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः। एश आदिशित्त्वाभावात्तस्मिन्नात्त्वम्। जग्ले।

२७६१। आतो युक्चिण्कृतोः।७।३।३३। आदन्तानां युगागमः स्याच्चिणि ञिति णिति कृति च। दायिता-दाता। दायिषीष्ट-दासीष्ट। अदायि। अदायिषाताम्, आदिषाताम्। अधायिषाताम् अधिषाताम्। अग्लायिषाताम्। अग्लासाताम्। हन्यते। 'अचिण्णलोः-' (सू २५७४) इत्युक्तेर्हनस्तो न। 'हो हन्तेः-' (सू ३५८) इति कुत्वम्। घानिता। हन्ता। घानिष्यते-हनिष्यते। आशीर्लिङि वधादेशस्यापवादश्चिण्वद्भावः। आर्धधातुके सीयुटीति विशेषविहितत्वात्। घानिषीष्ट। पक्षे। वधिषीष्ट। अघानि। अघानिषाताम्। अहसाताम्। पक्षे वधादेशः। अवधि। अवधिषाताम्। अघानिष्यत-अहनिष्यत। न च स्यादिषु चिण्वदित्यतिदेशाद्वध देशः स्यादिति वाच्यम्। 'अङ्गस्य' (सू २००) इत्यधिकारादाङ्गस्यैवातिदेशात्। गृह्यते। चिण्वदिटो न दीर्घत्वम्। प्रकृतस्य वलादिलक्षणस्येटो 'ग्रहोऽलिटि'- (सू २५६२) इत्यनेन दीर्घविधानात्। ग्राहिता-ग्रहीता। ग्राहिष्यते-ग्रहीष्यते। ग्राहिषीष्ट-ग्रहीषीष्ट। अग्राहि। अग्राहिषाताम्-अग्रहीषाताम्। दृश्यते। अदर्शि। अदर्शिषाताम्। सिचः कित्त्वादम्। अदृक्षाताम्। गिरतेर्लुङि ध्वमि चतुराधिकं शतम्। तथा हि। चिण्वदिटो दीर्घो नेत्युक्तम्। अगारिध्वम्। द्वितीये त्विटि 'वृतो वा' (सू २३९१) इति वा दीर्घः। अगरीध्वम्-अगरिध्वम्। एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि। इत्थं षण्णवतिः। 'लिङ्सिचोः-' (सू २५२८) इति विकल्पत्वादिडभावे 'उश्च' (सू २३६८) इति कित्त्वम्। रपरत्वं 'हलि च' (सू ३५४) इति दीर्घः। 'इणः षीध्वम्-' (सू २२४७) इति नित्यं ढत्वम्। अगीर्ढ्वम्। ढत्वमानां द्वित्वविकल्पेऽष्टौ। उक्तषण्णवत्या सह संकलने उक्ता संख्येति।

इट दीर्घश्चिण्वदिट् लत्वढत्वे द्वित्वत्रिकं तथा।

इत्यष्टानां विकल्पेन चतुर्भिराधिकं शतम्॥

हेतुमण्ण्यन्तात्कर्मणि लः यक् णिलोपः। शम्यते मोहो मुकुन्देन।

२७६२। चिण्णमुलोर्दीर्घोऽन्यतरस्याम्।६।४।९३। चिण्परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात्। प्रकृतो 'मितां ह्रस्वः' (सू २५६८) एव तु न विकल्पितः। ण्यन्ताण्णौ ह्रस्वविकल्पासिद्धेः। दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति। ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम्। भाष्ये तु 'पूर्वत्रासिद्धे न स्थानिवत्' इत्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः। णाविति जातिपरो निर्देशः। दीर्घग्रहणं वेदं मास्त्विति तदाशयः। शामिता-शमिता-शमयिता। शामिष्यते-शमिष्यते-शमयिष्यते। यङन्ताण्णिच्। शंशम्यते। शंशामिता-शंशमिता-शंशमयिता। यङ्लुगन्ताण्णिच्यप्येवम्। भाष्यमते तु यङन्ताच्चिण्वदिटि दीर्घो नास्तीति विशेषः। ण्यन्तत्वाभावे। शम्यते मुनिना।

२७६३। नोदात्तोपदेशस्य मान्तस्यानाचमेः।७।३।३४। उपधाया वृद्धिर्न स्याच्चिणि ञिति कृति च। अशमि। अदमि। 'उदात्तोपदेशस्य' इति किम्। अगामि। 'मान्तस्य' किम्। अवादि। 'अनाचमेः' किम्। आचामि। 'अनाचमिकमिवमीनामिति वक्तव्यम्' (वा ४५१८)। चिणि 'आयादयः-' (सू २३०५) इति णिङभावे। अकामि।

णिङ्णिचोरप्येवम्। अवामि। 'वध हिंसायाम्'। हलन्तः। 'जनिवध्योः–' (सू २५१२) इति न वृद्धिः। अवधि। जाग्रोऽविचिण्णल्ङित्सु' (सू २४८०) इत्युक्तेर्न गुणः। अजागारि।

२७६४। भञ्जेश्च चिणि। ६। ४। ३३। नलोपो वा स्यात्। अभाजि–अभञ्जि।

२७६५। विभाषा चिण्णमुलोः। ७। १। ६९। लभेर्नुमागमो वा स्यात्। अलम्भि–अलाभि। व्यवस्थितविकल्पत्वात्प्रादेर्नित्यं नुम्। प्रालम्भि। द्विकर्मकाणां तु

गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्।
बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया।
प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः॥ (१०९०-१०९९ वार्तिकार्थः)

गौर्दुह्यते पयः। अजा ग्रामं नीयते। ह्रियते। कृष्यते। उह्यते। बोध्यते माणवकं धर्मः। माणवको धर्ममिति वा। भोज्यते माणवकमोदनः। माणवक ओदनं वा। देवदत्तो ग्रामं गम्यते। 'अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते'। मासो मासं वा आस्यते देवदत्तेन। णिजन्तात्तु प्रयोज्ये प्रत्ययः। मासमास्यते माणवकः।

इति भावकर्मतिङ्प्रकरणम्।

अथ कर्मकर्तृतिङ्प्रकरणम्।

यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते। स्वव्यापारे स्वतन्त्रत्वात्। तेन पूर्वं करणत्वादिसत्त्वेऽपि संप्रति कर्तृत्वात्कर्तरि लकारः। साध्वसिश्छिनत्ति। काष्ठानि पचन्ति। स्थाली पचति। कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका अपि प्रायेणाकर्मकास्तेभ्यो भावे कर्तरि च लकाराः। पच्यते ओदनेन। भिद्यते काष्ठेन। कर्तरि तु।

२७६६। कर्मवत्कर्मणा तुल्यक्रियः। ३। १। ८७। कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात्। कार्यातिदेशोऽयम्। तेन यगात्मनेपदचिण्चिण्वदिटः स्युः। कर्तुरभिहितत्वात्प्रथमा। पच्यते ओदनः। भिद्यते काष्ठम्। अपाचि। अभेदि। ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न। लकारवाच्य एव कर्ता कर्मवत्। 'लिङ्याशिष्यङ्' (सू ३४३४) इति द्विलकारकात् 'लः' इत्यनुवृत्तेः भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः। अत एव कृत्यक्तखलर्थाः कर्मकर्तरि न भवन्ति। किं तु भाव एव। भेत्तव्यं कुसूलेन। ननु पचिभिद्योः कर्मस्था क्रिया विक्लित्तिर्द्विधाभवनं च। सैवेदानीं कर्तृस्था न तु तत्तुल्या। सत्यम्। कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः। 'कर्मणा' इति किम्। करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत्। किंच। कर्तृस्थक्रियेभ्यो माभूत्। गच्छति ग्रामः। आरोहति हस्ती। अधिगच्छति शास्त्रार्थः। स्मरति श्रद्दधाति वा। यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्वेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र। न हि पक्वापक्वतण्डुलेष्विवगतागत ग्रामेषु वैलक्षण्यमुपलभ्यते। करोतिरुत्पादनार्थः। उत्पत्तिश्च कर्मस्था। तेन करिष्यते घट इत्यादि। यत्नार्थत्वे तु नैतत्सिध्येत्। ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात्। एतेनानुव्यवस्यतेऽर्थ इति व्याख्यातम्। कर्तृस्थत्वेन यगभावाच्छ्यानि कृत ओलोपे च रूपसिद्धेः।

ताच्छील्यादावयं चानश्न् त्वात्मनेपदम् । 'सकर्मकाणां प्रतिषेधो वक्तव्यः' (वा १८७३)। अन्योन्यं स्पृशतः । अजा ग्रामं नयति । 'दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम्' (वा १८७६)।

२७६७। न दुहस्नुनमां यक्चिणौ । ३ । १ । ८९ । एषां कर्मकर्तरि यक्चिणौ न स्तः। दुहेरनेन यक एव निषेधः। चिण्तु विकल्पिष्यते। शप् लुक्। गौः पयो दुग्धे।

२७६८। अचः कर्मकर्तरि । ३ । १ । ६२ । अजन्ताच्चेश्चिण्वा स्यात्कर्मकर्तरि तशब्दे परे। अकारि-अकृत।

२७६९। दुहश्च । ३ । १ । ६३ । अदोहि । पक्षे क्सः । 'लुग्वा-' (सू २३६९) इति पक्षे लुक्। अदुग्ध-अधुक्षत। उदुम्बरः फलं पच्यते । 'सृजियुज्योः श्यंस्तु' (वा १८७७) अनयोः सकर्मकयोः कर्ता बहुलं कर्मवद्यगपवादश्च श्यन्वाच्य इत्यर्थः । 'सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम्' (वा ५०५४) सृज्यते स्रजं भक्तः । श्रद्धया निष्पादयतीत्यर्थः। असर्जि । युज्यते ब्रह्मचारी योगम् । 'भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्' (वा १८८०) भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वाच्यमित्यर्थः । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ष्ट । गिरते । अगीर्ष्ट । आद्रियते। आदृत । किरादिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियात्वम् ।

२७७०। न रुधः । ३ । १ । ६४ । अस्माच्लेश्चिण्न । अन्वारुद्ध गौः कर्मकर्तरीत्येव। अन्वारोधि गौर्गोपेन ।

२७७१। तपस्तपःकर्मकस्यैव । ३ । १ । ८८ । कर्ता कर्मवत्स्यात् । विध्यर्थमिदम्। एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः। 'तपोऽनुतापे च' (सू २७६०) इति चिण्निषेधात्सिच्। अतप्त । 'तपःकर्मकस्य' इति किम्। उत्तपति सुवर्णं सुवर्णकारः। 'न दुहस्नुनमां यक्चिणौ' (सू २७६७)। प्रस्नुते। प्रास्नाविष्ट-प्रास्नोष्ट । नमते दण्डः। अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः । यक्चिणोः प्रतिषेधे 'हेतुमण्णिश्रिब्रूञामुपसंख्यानम्' (वा १८८१)। कारयते । अचीकरत । उच्छ्रयते दण्डः। उदशिश्रियत। चिण्वदिट् तु स्यादेव। कारिष्यते। उच्छ्रायिष्यते ब्रूते कथाः । अवोचत। भारद्वाजीयाः पठन्ति । 'णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम्' (वा १८८२)। पुच्छमुदस्यति उत्पुच्छयते गौः। अन्तर्भावितण्यर्थतायाम्। उत्पुच्छयते गाम्। पुनः कर्तृत्वविवक्षायाम्। उत्पुच्छयते गौः। उदपुपुच्छत । यक्चिणोः प्रतिषेधाच्छण्चङौ । श्रन्थिग्रन्थ्योराधृषीयत्वाण्णिजभावपक्षे ग्रहणम्। ग्रन्थति ग्रन्थम्। श्रन्थति मेखलां देवदत्तः। ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्र्यादिकयोस्तु । श्रथ्नीते । ग्रथ्नीते स्वयमेव। विकुर्वते सैन्धवाः। वल्गन्तीत्यर्थः। 'वेः शब्दकर्मणः' (सू २७०७) 'अकर्मकाच्च' (सू २७०८) इति तङ्। अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे। विकुर्वते सैन्धवाः। व्यकारिष्ट। व्यकारिषाताम्। व्यकारिषत। व्यकृत। व्यकृषाताम्। व्यकृषत।

---

१ अत्र च 'सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावो वाच्यश्चिणात्मनेपदार्थः' इति भाष्यमानम्।

२७७२। कुषिरजोः प्राचां श्यन्परस्मैपदं च। ३। १। ९०। अनयोः कर्मकर्तरि न यक् किं तु श्यन्परस्मैपदं च। आत्मनेपदापवादः। कुष्यति-कुष्यते पादः। रज्यति-रज्यते वस्त्रम्। यगविषये तु नास्य प्रवृत्तिः। कोषिषीष्ट। रङ्क्षीष्ट।

इति कर्मकर्तृतिङ्प्रकरणम्।

अथ लकारार्थप्रकरणम्।

२७७३। अभिज्ञावचने लृट्। ३। २। ११२। स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात्। लङोऽपवादः। स्मरसि कृष्ण गोकुले वत्स्यामः। एवं बुध्यसे चेतयसे इत्यादियोगेऽपि। तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसंभवात्।

२७७४। न यदि। ३। २। ११३। यद्योगे उक्तं न। अभिजानासि कृष्ण यद्वने अभुञ्ज्महि।

२७७५। विभाषा साकाङ्क्षे। ३। २। ११४। उक्तविषये लृड्वा स्यात्। लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः। स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्याम वासो लक्षणं चारणं लक्ष्यम्। पक्षे लङ्। यच्छब्दयोगेऽपि 'न यदि' (सू २७७४) इति बाधित्वा परत्वाद्विकल्पः। 'परोक्षे लिट्' (सू २१७१)। चकार। उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम्। 'सुप्तोऽहं किल विललाप'। 'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्'। 'अत्यन्तापह्नवे लिड्वक्तव्यः' (वा २०८४)। कलिङ्गेष्ववात्सीः। नाहं कलिङ्गाञ्जगाम।

२७७६। हशश्वतोर्लङ् च। ३। २। ११६। अनयोरुपपदयोर्लिड्विषये लङ् स्यात्। चाल्लिट्। इति हाकरोच्चकार वा। शश्वदकरोच्चकार वा।

२७७७। प्रश्ने चासन्नकाले। ३। २। ११७। प्रष्टव्यः प्रश्नः। आसन्नकाले पृच्छ्यमानेऽर्थे लिड्विषये लङ्लिटौ स्तः। अगच्छत्किम्। जगाम किम्। अनासन्ने तु कंसं जघान किम्।

२७७८। लट् स्मे। ३। २। ११८। लिटोऽपवादः। यजति स्म युधिष्ठिरः।

२७७९। अपरोक्षे च। ३। २। ११९। भूतानद्यतने लट् स्यात्स्मयोगे। एवं स्म पिता ब्रवीति।

२७८०। ननौ पृष्टप्रतिवचने। ३। २। १२०। 'अनद्यतने' 'परोक्ष' इति निवृत्तम्। भूते लट् स्यात्। अकार्षीः किम्। ननु करोमि भोः।

२७८१। नन्वोर्विभाषा। ३। २। १२१। अकार्षीः किम्। ननु करोमि। नाकार्षम्। अहं नु करोमि। अहं न्वकार्षम्।

२७८२। पुरि लुङ् चास्मे। ३। २। १२२। अनद्यतनग्रहणं मण्डूकप्लुत्यानुवर्तते। पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् न तु स्मयोगे। पक्षे यथाप्राप्तम्। वसन्तीह पुरा छात्राः-अवात्सुः-अवसन्-ऊषुर्वा। 'अस्मे' किम्। यजति स्म पुरा। भविष्यतीत्यनुवर्तमाने।

२७८३। यावत्पुरानिपातयोर्लट्। ३। ३। ४। यावद्भुङ्क्ते। पुरा भुङ्क्ते। निपातावेतौ निश्चयं द्योतयतः। 'निपातयोः' किम्। यावद्दास्यते तावद्भोक्ष्यते। करणभूतया पुरा यास्यति।

२७८४ । विभाषा कदाकर्ह्योः । ३ । ३ । ५ । भविष्यति लट् वा स्यात् । कदा कर्हि वा भुङ्क्ते-भोक्ष्यते-भोक्ता वा ।

२७८५ । किंवृत्ते लिप्सायाम् । ३ । ३ । ६ । भविष्यति लड्वा स्यात् कं कतरं कतमं वा भोजयसि-भोजयिष्यसि-भोजयितासि वा । 'लिप्सायाम्' किम् । कः पाटलिपुत्रं गमिष्यति ।

२७८६ । लिप्स्यमानसिद्धौ च । ३ । ३ । ७ । लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्वा स्यात् । योऽन्नं ददाति-दास्यति-दाता वा । स स्वर्गं याति-यास्यति-याता वा ।

२७८७ । लोडर्थलक्षणे च । ३ । ३ । ८ । लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्वा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लृट्लुटौ ।

२७८८ । लिङ् चोर्ध्वमौहूर्तिके । ३ । ३ । ९ । ऊर्ध्वं मुहूर्ताद्भव ऊर्ध्वमौहूर्तिकः । निपातनात्समास उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्लटौ वा स्तः मुहूर्तादुपरि उपाध्यायश्चेदागच्छेत्-आगच्छति-आगमिष्यति-आगन्ता वा । अथ त्वं छन्दोऽधीष्व ।

२७८९ । वर्तमानसामीप्ये वर्तमानवद्वा । ३ । ३ । १३१ । समीपमेव सामीप्यम् । स्वार्थे ष्यञ् । 'वर्तमाने लट्' (सू २१५१) इत्यारभ्य 'उणादयो बहुलम्' (सू ३१६९) इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि एष गच्छामि-गमिष्यामि वा

२७९० । आशंसायां भूतवच्च । ३ । ३ । १३२ । वर्तमानसामीप्य इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीद्वर्षति-वर्षिष्यति वा धान्यमवाप्स्म-वपामः-वप्स्यामो वा । 'सामान्यातिदेशे विशेषानतिदेशः । तेन लङ्लिटौ न ।

२७९१ । क्षिप्रवचने लृट् । ३ । ३ । १३३ । क्षिप्रपर्याय उपपदे पूर्वविषये लृट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लृड्ग्रहणं लुटोऽपि उ विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः ।

२७९२ । आशंसावचने लिङ् । ३ । ३ । १३४ । आशंसावाचिन्युपपदे भविष्यति लिङ् । स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ।

२७९३ । नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः । ३ । ३ । १३५ । क्रियायाः सातत्ये सामीप्ये च लङ्लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित । सोमेनायष्ट । येयमावस्यागामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ।

२७९४ । भविष्यति मर्यादावचनेऽवरस्मिन् । ३ । ३ । १३६ । भविष्यति काले मर्यादोक्तावबरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः ।

२७९५ । कालविभागे चानहोरात्राणाम् । ३ । ३ । १३७ पूर्वसूत्रं सर्वमनुवर्तते ।

अहोरात्रसंबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः। योऽयं वत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे। 'अनहोरात्राणाम्' किम्! योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्राध्येतास्महे।

२७९६। परस्मिन्विभाषा। ३। ३। १३८। अवरस्मिन्वर्जं पूर्वसूत्रद्वयमनुवर्तते। अप्राप्तविभाषेयम्। योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे। अध्येतास्महे। 'लिङ्निमित्ते लृङ् क्रियातिपत्तौ' (सू २२२९) भविष्यतीत्येव। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्।

२७९७। भूते च। ३। ३। १४०। पूर्वसूत्रं संपूर्णमनुवर्तते।

२७९८। वोताप्योः। ३। ३। १४१। 'वा' 'आ' 'उताप्योः' 'उताप्योः–' (सू २८०९) इत्यतःप्राग्भूते लिङ्निमित्ते लृङ् चेत्यधिक्रियते। पूर्वसूत्रं तु 'उताप्योः' इत्यादौ प्रवर्तत इति विवेकः।

२७९९। गर्हायां लडपिजात्वोः। ३। ३। १४२। आभ्यां योगे लट् स्यात्। कालत्रये गर्हायाम्। लुङादीन्परत्वादयं बाधते। अपि जायां त्यजसि। जातु गणिकामाधत्से। गर्हितमेतत्।

२८००। विभाषा कथमि लिङ् च। ३। ३। १४३। गर्हायामित्येव। कालत्रये लिङ्। चाल्लट्। कथं धर्मं त्यजेस्त्यजसि वा। पक्षे कालत्रये लकाराः। अत्र भविष्यति नित्यं लृङ् भूते वा। कथं नाम तत्रभवान्धर्ममत्यक्ष्यत्।

२८०१। किंवृत्ते लिङ्लृटौ। ३। ३। १४४। गर्हायामित्येव। विभाषा तु नानुवर्तते। कः–कतरः–कतमो वा हरिं निन्देत्–निन्दिष्यति वा। लृङ् प्राग्वत्।

२८०२। अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि। ३। ३। १४५। गर्हायामिति निवृत्तम्। अनवक्लृप्तिरसंभावना। अमर्षोऽक्षमा। न संभावयामि न मर्षये वा भवान्हरिं निन्देत्–निन्दिष्यति वा। कः–कतरः–कतमो वा हरिं निन्देत्– निन्दिष्यति वा। लृङ् प्राग्वत्।

२८०३। किंकिलास्त्यर्थेषु लृट्। ३। ३। १४६। अनवक्लृप्त्यमर्षयोरित्येतद् 'गर्हायां च' (सू २८०६) इति यावदनुवर्तते। किंकिलेति समुदायः क्रोधद्योतक उपपदम्। अस्त्यर्थाः अस्तिभवतिविद्यतयः। लिङोऽपवादः। न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे। अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि। अत्र लृङ् न।

२८०४। जातुयदोर्लिङ्। ३। ३। १४७। 'यदायद्योरुपसंख्यानम्' (वा २२७२)। लृटोऽपवादः। जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि। लृङ् प्राग्वत्।

२८०५। यच्चयत्रयोः। ३। ३। १४८। यच्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्षयामि।

२८०६। गर्हायां च। ३। ३। १४९। अनवक्लृप्त्यमर्षयोरिति निवृत्तम्। यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात्। यच्च यत्र वा त्वं शूद्रं याजयेः। अन्याय्यं तत्।

२८०७। चित्रीकरणे च। ३। ३। १५०। यच्च यत्र वा त्वं शूद्रं याजयेः। आश्चर्यमेतत्।

19*

२८०८। शेषे लृडयदौ। ३। ३। १५१। यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात्। आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति। 'अयदौ' किम्। आश्चर्यं यदि सोऽधीयीत।

२८०९। उताप्योः समर्थयोर्लिङ्। ३। ३। १५२। बाढमित्यर्थेऽनयोस्तुल्यार्थता। उत अपि वा हन्यादघं हरिः। 'समर्थयोः' किम्। उत दण्डः पतिष्यति। अपिधास्यति द्वारम्। प्रश्नः प्रच्छादनं च गम्यते। इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लिङ्।

२८१०। कामप्रवेदनेऽकच्चिति। ३। ३। १५३। स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कच्चिति। कामो मे भुञ्जीत भवान्। 'अकच्चिति' इति किम्। कच्चिज्जीवति।

२८११। संभावनेऽलमिति चेत्सिद्धाप्रयोगे। ३। ३। १५४। अलमर्थोऽत्र प्रौढिः संभावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते। संभावने लिङ् स्यात्, तच्चेत्संभावनमलमिति सिद्धाप्रयोगे सति। अपि गिरिं शिरसा भिन्द्यात्। 'सिद्धाप्रयोगे' किम्। अलं कृष्णो हस्तिनं हनिष्यति।

२८१२। विभाषा धातौ संभावनवचनेऽयदि। ३। ३। १५५। पूर्वसूत्रमनुवर्तते। संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे। पूर्वेण नित्ये प्राप्ते वचनम्। संभावयामि भुञ्जीत भोक्ष्यते वा भवान्। 'अयदि' किम्। संभावयामि यद्भुञ्जीथास्त्वम्।

२८१३। हेतुहेतुमतोर्लिङ्। ३। ३। १५६। वा स्यात्। कृष्णं नमेच्चेत्सुखं यायात्। कृष्णं नंस्यति चेत्सुखं यास्यति। 'भविष्यत्येवेष्यते' (वा २२७५)। नेह। हन्तीति पलायते।

२८१४। इच्छार्थेषु लिङ्लोटौ। ३। ३। १५७। इच्छामि भुञ्जीत–भुङ्क्तां वा भवान्। एवं कामये प्रार्थय इत्यादियोगे बोध्यम्। 'कामप्रवेदन इति वक्तव्यम्' (वा २२७६)। नेह। इच्छन्करोति।

२८१५। लिङ् च। ३। ३। १५९। समानकर्तृकेषु इच्छार्थेषु लिङ्। भुञ्जीयेतीच्छति।

२८१६। इच्छार्थेभ्यो विभाषा वर्तमाने। ३। ३। १६०। लिङ् स्यात्पक्षे लट्। इच्छेत्–इच्छति। कामयेत्–कामयते। 'विधिनिमन्त्रण–' (सू२२०८) इति लिङ्। विधौ। यजेत। निमन्त्रणे। इह भुञ्जीत भवान्। आमन्त्रणे। इहासीत। अधीष्टे। पुत्रमध्यापयेद्भवान्। 'संप्रश्ने' किं। भो वेदमधीयीय उत तर्कम्। प्रार्थने। भो भोजनं लभेय। एवं लोट्।

२८१७। प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च। ३। ३। १६३। प्रैषो विधिः। अतिसर्गः कामचारानुज्ञा। भवता यष्टव्यम्। भवान्यजताम्। चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम्।

२८१८। लिङ् चोर्ध्वमौहूर्तिके। ३। ३। १६४। प्रैषादयोऽनुवर्तन्ते। मुहूर्तादूर्ध्वं यजेत–यजताम्–यष्टव्यम्।

२८१९। स्मे लोट् । ३ । ३ । १६५ । पूर्वसूत्रस्य विषये। लिङः कृत्यानां चापवादः । ऊर्ध्वं मुहूर्ताद्यजतां स्म ।

२८२० । अधीष्टे च । ३ । ३ । १६६ । स्म उपपदेऽधीष्टे लोट् स्यात् । त्वं स्माध्यापय ।

२८२१ । लिङ्यदि । ३ । ३ । १६८ । यच्छब्द उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ।

२८२२ । अर्हे कृत्यतृचश्च । ३ । ३ । १६९ । चाल्लिङ् । त्वं कन्यां वहेः ।

२८२३ । शकि लिङ् च । ३ । ३ । १७२ । शक्तौ लिङ् स्यात् । चात्कृत्याः । भारं त्वं वहेः । 'माङि लुङ्' (सू २२१९) मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ्[1] । किं तु माशब्दः ।

२८२४ । धातुसंबन्धे प्रत्ययाः । ३ । ४ । १ । धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन्ददर्श । भूते लट् । अतीतवासकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ।

२८२५ । क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः । ३ । ४ । २ । पौनःपुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तः । तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ।

२८२६ । समुच्चयेऽन्यतरस्याम् । ३ । ४ । ३ । अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ।

२८२७ । यथाविध्यनुप्रयोगः पूर्वस्मिन् । ३ । ४ । ४ । आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ।

२८२८ । समुच्चये सामान्यवचनस्य । ३ । ४ । ५ । समुच्चये लोड्विधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्यथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः । 'क्रियासमभिहारे द्वे वाच्ये' (वा ४६९९) । याहि याहीति याति । पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानं यानं यातीत्यस्य । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यात यातेति यूयं याथ । याहि याहीत्ययासीत्-यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमिति यूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ध्वमास्वदध्वमित्यभ्यवहरध्वम् । पक्षे हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून्पिबति धानाः खादति अन्नं भुङ्क्ते दाधिकमास्वादते । एतेन

---

१ वस्तुतः स नास्त्येव । 'आङ्माङोश्च' इति सूत्रेभाष्ये तथा ध्वनितत्वात्–इति शेखरकृत् ॥

'पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥'

इति व्याख्यातम् । अवस्कन्दनलवनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति व्याख्यानं भ्रममूलकमेव द्वितीयसूत्रे क्रियासमभिहार इत्यस्याननुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देत्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ।

इति लकारार्थप्रकरणम् ।

अथ कृदन्तकृत्यप्रकरणम् ।

२८२९ । धातोः । ३ । १ । ९१ । आ तृतीयसमाप्तेरधिकारोऽयम् । 'तत्रोपपदं सप्तमीस्थम्' (सू ७८१) । 'कृदतिङ्' (सू ३०४) ।

२८३० । वासरूपोऽस्त्रियाम् । ३ । १ । ९४ । परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात्स्त्र्यधिकारोक्तं विना ।

२८३१ । कृत्याः । ३ । १ । ९५ । अधिकारोऽयं ण्वुलः प्राक् ।

२८३२ । कर्तरि कृत् । ३ । ४ । ६७ । कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ।

२८३३ । तयोरेव कृत्यक्तखलर्थाः । ३ । ४ । ७० । एते भावकर्मणोरेव स्युः ।

२८३४ । तव्यत्तव्यानीयरः । ३ । १ । ९६ । धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थौ । एधितव्यम् । एधनीयं त्वया । भाव औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया । 'वसेस्तव्यत्कर्तरि णिच्च' (वा १९२०) । वसतीति वास्तव्यः । 'केलिमर उपसंख्यानम्' (वा १९१९) । पचेलिमा माषाः पक्तव्याः भिदेलिमाः सरलाः भेत्तव्याः । कर्मणि प्रत्ययः । वृत्तिकारस्तु 'कर्मकर्तरि चायमिष्यते' इत्याह । तद्भाष्यविरुद्धम् ।

२८३५ । कृत्यचः । ८ । ४ । २९ । उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् 'अचः' किम् । प्रमग्नः । 'निर्विण्णस्योपसंख्यानम्' (वा ५००४) । 'अचः' परत्वाभावान्नकारेण व्यवधानाच्चाप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ।

२८३६ । णेर्विभाषा । ८ । ४ । ३० । उपसर्गस्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तत्स्थस्य नस्य णो वा स्यात् । प्रयाप्रणीयम्—प्रयापनीयम् । 'विहितविशेषणम्' किम् । यका व्यवधाने यथा स्यात् । प्रयाप्यमाणपश्य । 'णत्वे दुर उपसर्गत्वं न' इत्युक्तम् । दुर्यानम् । दुर्यापनम् ।

२८३७ । हलश्चेजुपधात् । ८ । ४ । ३१ । हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम्—प्रकोपनीयम् । 'हलः' किम् । प्रोहणीयम् । 'इजुपधात्' किम् । प्रवपणीयम् ।

२८३८ । इजादेः सनुमः । ८ । ४ । ३२ । सनुमश्चेद्भवति तर्हि इजादेहलन्ताद्विहितो यः कृत्तत्स्थस्यैव । प्रेङ्खणीयम् । 'इजादेः' किम् । 'मगि समर्पणे' । प्रमङ्गनीयम् । नुम्ग्रहणम-

नुस्वारोपलक्षणम् । 'अट्कुप्वाङ्-' (सू १९७) इति सूत्रेऽप्येवम् । तेनेह न । प्रेन्वनम् । इह-तु स्यादेव । प्रोम्भणम् ।

२८३९ । वा निंसनिक्षनिन्दाम् । ८ । ४ । ३३ । एषां नस्य णो वा स्यात्कृति परे । प्रणिंसितव्यम्-प्रनिंसितव्यम् ।

२८४० । न भाभूपूकमिगमिप्यायीवेपाम् । ८ । । ४ । ३४ । एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् । 'पूञ एवेह ग्रहणमिष्यते' (वा ५०११) पूङस्तु प्रपवणीयः सोमः । 'ण्यन्तभादीनामुपसंख्यानम्' (वा ५०१२) । प्रभापनीयम् 'ख्शाञः शस्य यो वा' (वा १५८४) इत्युक्तम् णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ।

२८४१ । कृत्यल्युटो बहुलम् । ३ । ३ । ११३ । स्नान्त्यनेन स्नानीयं चूर्णम् । दीयते-ऽस्मै दानीयो विप्रः ।

२८४२ । अचो यत् । ३ । १ । ९७ । अजन्ताद्धातोर्यत्स्यात् । चेयम् । जेयम् । अज्ग्र-हणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यदादिष्वेव यतोऽपि सुपठत्वात् ।

२८४३ । ईद्यति । ६ । ४ । ६५ । यति परे आत ईत्स्यात् । गुणः । देयम् । ग्लेयम् । 'तकिशसिचतियतिजनिभ्यो यद्वाच्यः' (वा १९२२) । तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । 'जनिव ध्योश्च' (सू २५१२) इति निषेधात् । 'हनो वा यद्वधश्च वक्तव्यः' (वा १९२३) । वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ।

२८४४ । पोरदुपधात् । ३ । १ । ९८ । पवर्गान्तादुपधाद्यत्स्यात् ण्यतोऽपवादः । शप्यम् । लभ्यम् । 'नानुबन्धकृतमसारूप्यम्' । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ।

२८४५ । आङो यि । ७ । १ । ६५ । आङः परस्य लभेर्नुम्स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधत्वाभावात् ण्यदेव । आलम्भ्यो गौः ।

२८४६ । उपात्प्रशंसायाम् । ७ । १ । ६६ । उपलम्भ्यः साधुः । 'स्तुतौ' किम् । उप-लब्धुं शक्य उपलभ्यः ।

२८४७ । शकिसहोश्च । ३ । १ । ९९ । शक्यम् । सह्यम् ।

२८४८ । गदमदचरयमश्चानुपसर्गे । ३ । १ । १०० । गद्यम् । मद्यम् । चर्यम् । 'चरेराङि चागुरौ' (वा १९२५) । आचर्यो देशः । गन्तव्य इत्यर्थः । 'अगुरौ' किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्मा भूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव । तेन 'तत्र न भवेद्विनियम्यम्' (वा १९३०) इति वार्तिकप्रयोगात् । एतेन 'अनियम्यस्य नायुक्तिः' । 'त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादि व्याख्यातम् । नियमे साधुरिति वा ।

२८४९ । अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु । ३ । १ । १०१ । वदेर्नञ्युपपदे 'वदः सुपि-' (सू २८९४) इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवद्यं पापम् । 'गर्ह्ये' किम् । अनुद्यं गुरुनाम । तद्धि न गर्ह्यं वचनानर्हं च ।

'आत्मनाम गुरोर्नाम नामातिकृपणस्य च ।
श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥'

इति स्मृतेः। पण्या गौः। व्यवहर्तव्येत्यर्थः। पाण्यमन्यत्। स्तुत्यर्हमित्यर्थः। अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत्। शतेन वर्या कन्या। वृत्यान्या।

२८५०। वह्यं करणम्। ३।१। १०२। वहन्त्यनेनेति वह्यं शकटम्। 'करणम्' किम्। वाह्यम्–वोढव्यम्।

२८५१। अर्यः स्वामिवैश्ययोः। ३।१।१०३। 'ऋ गतौ' अस्माद्यत्। ण्यतोऽपवादः। अर्यः स्वामी वैश्यो वा। 'अनयोः' किम्। आर्यो ब्राह्मणः प्राप्तव्य इत्यर्थः।

२८५२। उपसर्या काल्या प्रजने। ३।१। १०४। गर्भग्रहणे प्राप्तकाला चेदित्यर्थः। उपसर्या गौः। गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः। 'प्रजने काल्या' इति किम्। उपसार्या काशी। प्राप्तव्येत्यर्थः।

२८५३। अजर्यं संगतम्। ३।१।१०५। नञ्पूर्वाज्जीर्यतेः कर्तरि यत्संगतं चेद्विशेष्यम्। न जीर्यतीत्यजर्यम्। 'तेन संगतमार्येण रामाजर्यं कुरु द्रुतम्' इति भट्टिः। 'मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध' इत्यत्र तु संगतमिति विशेष्यमध्याहार्यम्। 'संगतम्' किम्। अजरिता कम्बलः। भावे तु संगतकर्तृकेऽपि ण्यदेव। अजार्यं संगतेन।

२८५४। वदः सुपि क्यप्च। ३।१। १०६। उत्तरसूत्रादिह भाव इत्यपकृष्यते। वदेर्भावे क्यप्स्याच्चाद्यदनुपसर्गे सुप्युपपदे। ब्रह्मोद्यम्–ब्रह्मवद्यम्। ब्रह्म वेदः तस्य वदनमित्यर्थः। कर्मणि प्रत्ययावित्येके। उपसर्गे तु ण्यदेव। अनुवाद्यम्। अपवाद्यम्।

२८५५। भुवो भावे। ३।१।१०७। क्यप्स्यात्। ब्रह्मणो भावो ब्रह्मभूयम्। सुपीत्येव। भव्यम्। अनुपसर्ग इत्येव। प्रभव्यम्।

२८५६। हनस्त च। ३।१।१०८। अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चान्तादेशः। ब्रह्मणो हननं ब्रह्महत्या। स्त्रीत्वं लोकात्।

२८५७। एतिस्तुशास्वृदृजुषः क्यप्। ३।१।१०९। एभ्यः क्यप्स्यात्।

२८५८। ह्रस्वस्य पिति कृति तुक्। ६।१।७१। इत्यः। स्तुत्यः। 'शास इदङ्हलोः'(सू २४८६)। शिष्यः।'वृ' इति वृञो ग्रहणं न वृङः। वृत्यः। वृङस्तु वार्या ऋत्विजः आदृत्यः। जुष्यः। पुनः क्यब्उक्तिः परस्यापि ण्यतो बाधनार्था। अवश्यस्तुत्यः। 'शासिदुहिगुहिभ्यो वा' (वा १८३५) इति काशिका। शस्यम्। शंस्यम्। दुह्यम्। दोह्यम्। गुह्यम्। गोह्यम्। 'प्रशस्यस्य श्रः' (सू २००९) 'ईडवन्दवृशंसदुहां ण्यतः'(सू ३७०२) इति सूत्रद्वयबलाच्छंसेः सिद्धम्। इतरयोस्तु मूलं मृग्यम्। 'आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम्' (वा १९२५)। 'अञ्जू' व्यक्तिम्रक्षणादिषु। बाहुलकात्करणे क्यप्। 'अनिदिताम्–' (सू ४१५) इति नलोपः। आज्यम्।

२८५९। ऋदुपधाच्चाक्लृपिचृतेः। ३।१।११०। 'वृत्'। वृत्यम्। 'वृधु'। वृध्यम्। क्लृपिचृत्योस्तु। कल्प्यम्। चर्त्यम्। 'तपरकरणम्' किम्। 'कृत्'। कीर्त्यम्। अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत्। णिजन्तात्तु यदेव।

२८६०। ई च खनः। ३।१।१११। चात्क्यप्। आद्गुणः। खेयम्। 'इ च' इति ह्रस्वः सुपठः।

२८६१। भृञोऽसंज्ञायाम्। ३।१। ११२। भृत्याः कर्मकरा भर्तव्या इत्यर्थः।

क्रियाशब्दोऽयं न तु संज्ञा। 'समश्च बहुलम्' (वा १९४०)। संभृत्याः। संभार्याः। असंज्ञायामेव विकल्पार्थमिदं वार्तिकम्। 'असंज्ञायाम्' किम्। भार्या नाम क्षत्रियाः। अथ कथं भार्या वधूरिति। इह हि 'संज्ञायां समज–' (सू ३२७६) इति क्यपा भाव्यम्। संज्ञापर्युदासस्तु पुंसि चरितार्थः। सत्यम्। बिभर्तेर्भृ इति दीर्घान्तात्क्यादेर्वा ण्यत्। क्यप्तु भरतेरेव। तदनुबन्धकग्रहणे–' इति परिभाषया।

२८६२। मृजेर्विभाषा। ३। १। ११३। मृजेः क्यब्वा स्यात्। पक्षेण्यत्। मृज्यः।

२८६३। चजोः कु घिण्ण्यतोः। ७। ३। ५२। चस्य जस्य च कुत्वं स्याद्धिति ण्यति च प्रत्यये परे। 'निष्ठायामनिट इति वक्तव्यम्' (वा ४५९१)। तेनेह न। गर्ज्यम्। 'मृजेर्वृद्धिः' (सू २४७३)। मार्ग्यः।

२८६४। न्यङ्क्वादीनां च।। ७। ३। ५३। कुत्वं स्यात्। न्यङ्कुः। 'नावञ्चेः' (उणा-१७) इत्युप्रत्ययः।

२८६५। राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः। ३। १। ११४। एते सप्त क्यबन्ता निपात्यन्ते। राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः। यद्वा। लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रेत्यधिकरणे क्यान्निपातनाद्दीर्घः। राजसूयः–राजसूयम्। अर्धर्चादिः। सरत्याकाशे सूर्यः। कर्तरि क्यन्निपातनादुत्त्वम्। यद्वा 'षू प्रेरणे' तुदादिः। सुवति कर्माणि लोकं प्रेरयति क्यपो रुट्। मृषोपपदाद्वदेः कर्मणि नित्यं क्यप्। मृषोद्यम्। विशृष्यनिद्रोऽयम्। 'उच्छ्रायसौन्दर्यगुणा मृषोद्याः'। रोचते रुच्यः। गुपेरादेः कुत्वं च संज्ञायाम्। सुवर्णरजतभिन्नं धनं कुप्यम्। गोप्यमन्यत्। कृष्टे स्वयमेव पच्यन्ते कृष्टपच्याः कर्मकर्तरि शुद्धे तु कर्मणि कृष्टपाक्याः। न व्यथतेऽव्यथ्यः।

२८६६। भिद्योद्ध्यौ नदे। ३। १। ११५। भिदेरुज्झेश्च क्यप्। उज्झेर्धत्वं च। भिनत्ति कूलं भिद्यः। उज्झत्युदकमुद्ध्यः। 'नदे' किम्। भेत्ता। उज्झिता।

२८६७। पुष्यसिध्यौ नक्षत्रे। ३। १। ११६। अधिकरणे क्यन्निपात्यते। पुष्यन्त्यस्मिन्नर्थाः पुष्यः। सिध्यन्त्यस्मिन्सिध्यः।

२८६८। विपूयविनीयजित्या मुञ्जकल्कहलिषु। ३। १। ११७। पूङ्नीजिभ्यः क्यप्। विपूयो मुञ्जः। रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः। विनीयः कल्कः। पिष्ट औषधिविशेष इत्यर्थः। पापमिति वा। जित्यो हलिः। बलेन कृष्टव्य इत्यर्थः। कृष्टसमीकरणार्थं स्थूलकाष्ठम्। अन्यत्तु विपव्यम्। विनेयम्। जेयम्।

२८६९। प्रत्यपिभ्यां ग्रहेः। ३। १। ११८। 'छन्दसीति वक्तव्यम्' (वा १९४४)। प्रतिगृह्यम्। अपिगृह्यम्। लोके तु प्रतिग्राह्यम्। अपिग्राह्यम्।

२८७०। पदास्वैरिबाह्यापक्ष्येषु च। ३। १। ११९। अवगृह्यम्। प्रगृह्यं पदम्। अस्वैरी परतन्त्रः। गृह्यकाः शुकाः। पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः। बाह्यायां ग्रामगृह्या सेना। ग्रामबहिर्भूतेत्यर्थः। स्त्रीलिङ्गनिर्देशात्पुंनपुंसकयोर्न। पक्षे भवः पक्ष्यः। दिगादित्वाद्यत्। आर्यैर्गृह्यत आर्यगृह्यः। तत्पक्षाश्रित इत्यर्थः।

२८७१। विभाषा कृवृषोः। ३। १। १२०। क्यप्स्यात्। कृत्यम्। वृष्यम्। पक्षे

२८७२ । ऋहलोर्ण्यत् ।३ । १ । १२४ । ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ध्यम् ।

२८७३ । युग्यं च पत्रे । ३ । १ । १२१ । पत्रं वाहनम् । युग्यो गौः । अत्र क्यप्कुत्वं च निपात्यते ।

२८७४ । अमावस्यदन्यतरस्याम् । ३ । १ । १२२ । अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रार्कावमावास्या—अमावस्या । 'ऋहलोर्ण्यत्' (सू २८७२) । 'चजोः—' (सू २८६३) इति कुत्वम् । पाक्यम् । 'पाणौ सृजेर्ण्यद्वाच्यः' (वा १९४६) । ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसर्ग्या रज्जुः । 'समवपूर्वाच्च' (वा १९४७) । समवसर्ग्या ।

२८७५ । न क्वादेः । ७ । ३ । ५९ । क्वादेर्धातोश्चजोः कुत्वं न । गर्ज्यम् । वार्तिककारस्तु 'चजोः—' (सू २८६३) इति सूत्रे 'निष्ठायामनिटः' इति पूरयित्वा 'न क्वादेः' (सू २८७५) इत्यादि प्रत्याचख्यौ । तेन अर्जितजिप्रभृतीनां न कुत्वं निष्ठायां सेट्त्वात् । मुचुग्लुञ्चुप्रभृतीनां तु क्वादित्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तं तथापि 'यथोत्तरं मुनीनां प्रामाण्यम्' ।

२८७६ । अजिव्रज्योश्च । ७ । ३ । ६० । न कुत्वम् । समाजः । परिव्राजः ।

२८७७ । भुजन्युब्जौ पाण्युपतापयोः । ७ । ३ । ६१ । एतयोरेतौ निपात्यौ । भुज्यतेनेनेति भुजः पाणिः । 'हलश्च' (सू ३३००) इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः उपतापो रोगः । 'पाण्युपतापयोः' किम् । भोगः समुद्गः ।

२८७८ । प्रयाजानुयाजौ यज्ञाङ्गे । ७ । ३ । ६२ । एतौ निपात्यौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । 'यज्ञाङ्गे' किम् । प्रयागः । अनुयागः ।

२८७९ । वञ्चेर्गतौ । ७ । ३ । ६३ । कुत्वं न । वञ्च्यम् । 'गतौ' किम् । वङ्क्यं काष्ठम् । कुटिलीकृतमित्यर्थः ।

२८८० । ओक उचः के । ७ । ३ । ६४ । उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषलौ । इगुपधलक्षणः कः । घञा सिद्धे अन्तोदात्तार्थमिदम् ।

२८८१ । ण्य आवश्यके । ७ । ३ । ६५ । कुत्वं न । अवश्यपाच्यम् ।

२८८२ । यजयाचरुचप्रवचर्चश्च । ७ । ३ । ६६ । ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । 'ऋच्' । अर्च्यम् । ऋदुपधत्वेऽप्यतएव ज्ञापकाण्ण्यत् । 'त्यजेश्च' (वा ४५५८) त्याज्यम् । 'त्यजिपूज्योश्च' इति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यं भाष्यानुक्तत्वात् । 'ण्यत्प्रकरणे त्यजेरुपसंख्यानम्' (वा ४५५८) इति हि भाष्यम् ।

२८८३ । वचोऽशब्दसंज्ञायाम् । ७ । ३ । ६७ । वाच्यम् । शब्दाख्यायां तु वाक्यम् ।

२८८४ । प्रयोज्यनियोज्यौ शक्यार्थे । ७ । ३ । ६८ । प्रयोक्तुं शक्यः प्रयोज्यो नियोक्तुं शक्यो नियोज्यो भृत्यः ।

२८८५ । भोज्यं भक्ष्ये । ७ । ३ । ६९ । भोग्यमन्यत् । 'ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम्' (वा १९५८) । लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ।

२८८६। ओरावश्यके। ३। १। १२५। उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये। लाव्यम्। पाव्यम्।

२८८७। आसुयुवपिरपित्रपिचमश्च ३। १। १२६। 'सुञ्'। आसाव्यम्। 'यु मिश्रणे'। याव्यम्। वाप्यम्। राप्यम्। त्राप्यम्। चाम्यम्[१]।

२८८८। आनाय्योऽनित्ये। ३। १। १२७। आङ्पूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते। दक्षिणाग्निविशेष एवेदम्। स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनात्। आनेयोऽन्यः। घटादिः। वैश्यकुलादेरानीतो दक्षिणाग्निश्च।

२८८९। प्रणाय्योऽसंमतौ। ३। १। १२८। संमतिः प्रीतिविषयीभवनं कर्मव्यापारः। तथा भोगेष्वादरोऽपि संमतिः। प्रणाय्यश्चोरः। प्रीत्यनर्ह इत्यर्थः। प्रणाय्योऽन्तेवासी। विरक्त इत्यर्थः। प्रणेयोऽन्यः।

२८९०। पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु। ३। १। १२९। मीयतेऽनेन पाय्यं मानम्। ण्यद्धात्वादेः पत्वं च। 'आतो युक्–' (सू २७६१) इति युक्। सम्यङ् नीयते होमार्थमग्निं प्रतीति सांनाय्यं हविर्विशेषः। ण्यदायादेशः समो दीर्घश्च निपात्यते। निचीयतेऽस्मिन्धान्यादिकं निकाय्यो निवासः। अधिकरणे ण्यत् आयो धात्वादेः कुत्वं च निपात्यते। धीयतेऽनया सामिदिति धाय्या ऋक्।

२८९१। क्रतौ कुण्डपाय्यसंचाय्यौ। ३। १। १३०। कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः। संचीयतेऽसौ संचाय्यः।

२८९२। अग्नौ परिचाय्योपचाय्यसमूह्याः। ३। १। १३१। अग्निधारणार्थे स्थलविशेष एते साधवः। अन्यत्र तु परिचेयम्। उपचेयम्। संवाह्यम्।

२८९३। चित्याग्निचित्ये च। ३। १। १३२। चीयतेऽसौ चित्योऽग्निः। अग्नेश्चयनमग्निचित्या। 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' (सू २८१७)। त्वया गन्तव्यम्। गमनीयम्। गम्यम्। इह लोटा बाधा मा भूदिति पुनः कृत्यविधिः 'स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्न' इति ज्ञापयति। तेन 'क्तल्युट्तुमुन्खलर्थेषु न–' इति सिद्धम्। 'अर्हे कृत्यतृचश्च' (सू २८२२) स्तोतुमर्हः स्तुत्यः स्तुतिकर्म। स्तोता स्तुतिकर्ता। लिङा बाधा मा भूदिति कृत्यतृचोर्विधिः।

२८९४। भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा। ३। ४। ६८। एते कृत्यान्ताः कर्तरि वा निपात्यन्ते। पक्षे तयोरेवेति सकर्मकात्कर्मणि। अकर्मकात्तु भावे ज्ञेयाः। भवतीति भव्यः। भव्यमनेन वा। गायतीति गेयः साम्नामयम्। गेयं सामानेन वा इत्यादि। 'शकि लिङ् च' (सू २८२३)। चात्कृत्याः। वोढुं शक्यो वोढव्यः। वहनीयो वाह्यः लिङा बाधा मा भूदिति कृत्प्रोक्तिः। लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे 'कृत्याश्च' इति सुत्यजम्। अर्हे कृत्यतृचोर्ग्रहणं च।

इति कृदन्तकृत्यप्रकरणम्।

---

१ 'आचाम्यम्' इति पाठः। यथाश्रुते वृद्ध्यनुपपत्तेः।

अथ कृदन्तप्रकरणम्।

२८९५। ण्वुल्तृचौ। ३। १। १३३। धातोरेतौ स्तः। 'कर्तरि कृत्' (सू २८३३) इति कर्त्रर्थे। 'युवोरनाकौ' (सू १२४७)। कारकः। कर्ता। वोढुमर्हो वोढा। कारिका। कर्त्री। 'गाङ्कुटा–' (सू २४६१) इति ङित्त्वम्। कुटिता। अङ्गिणादित्युक्तेर्न ङित्त्वम्। कोटकः। 'विज इट्' (सू २५३६) विजिता। 'हनस्तोऽचिण्णलोः' (सू २५७४)। घातकः। 'आतो युक्–' (सू २७६१) दायकः। 'नोदात्तोपदेशस्य–' (सू २७६३) इति न वृद्धिः। शमकः। दमकः। अनिटस्तु नियामकः। 'जनिवध्योश्च' (सू २५१२)। जनकः। 'वध हिंसायाम्'। वधकः। 'रधिजभोरचि' (सू २३०२)। रन्धकः। जम्भकः। 'नेट्यलिटि रधेः' (सू २५१६)। रधिता-रद्धा। 'मस्जिनशो:–' (सू २५१७) इति नुम्। मङ्क्ता। नंष्टा-नाशिता। 'रभेरशब्लिटोः' (सू २५८१)। रम्भकः। रब्धा। 'लभेश्च' (सू २५८२) लम्भकः। लब्धा। 'तीषसह–' (सू २३४०)। एषिता-एष्टा। सहिता-सोढा। दरिद्रातेरालोपः। दरिद्रिता। 'ण्वुलि न'। दरिद्रायकः। 'कृत्यल्युटः' (सू २८४१) इत्येव सूत्रमस्तु। यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात्। एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम्। पादाभ्यां ह्रियते पादहारकः। कर्मणि ण्वुल्। 'क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः' (वा ४४२२-२३) प्रक्रन्ता। 'कर्तरि' इति किम्। प्रक्रमितव्यम्। 'आत्मनेपद–' इति किम्। संक्रमिता। अनन्यभावो विषयशब्दः। तेन 'अनुपसर्गाद्वा' (सू २७१६) इति विकल्पार्हस्य न निषेधः। क्रमिना तदर्हत्वमेव तद्विषयत्वम्। तेन क्रन्तेत्यपीति केचित्। 'गमेरिट्–' (सू २४०१) इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति। संजिगमिषिता। एवं 'न वृद्भ्यश्चतुर्भ्यः' (सू २३४८) विवृत्सिता। यङन्ताण्ण्वुल्। अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः। पापचकः। यङ्लुगन्तात्तु पापाचकः।

२८९६। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। ३। १। १३४। नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच्स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। मधुसूदनः। विशेषेण भीषयतीति विभीषणः। लवणः। नन्द्यादिगणे निपातनाण्णत्वम्। ग्राही। स्थायी। मन्त्री। विशयी। वृद्ध्यभावो निपातनात्। विषयी। इह षत्वमपि। परिभावी-परिभवी। पाक्षिको वृद्ध्यभावो निपात्यते। पचादिराकृतिगणः। 'शिवशमरिष्टस्य करे' (सू ३४८९)। 'कर्मणि घटो ठच्' (सू १८३६) इति सूत्रयोः करोतेर्घटेश्चाच्प्रयोगात्। अच्प्रत्यये परे यङ्लुग्विधानाच्च। केषांचित्पाठस्त्वनुबन्धासंजनार्थः। केषांचित्प्रपञ्चार्थः। केषांचिद्बाधकबाधनार्थः। पचतीति पचः। नदट्। चोरट्। देवट्। इत्यादयष्टितः। नदी। चोरी। देवी। दीव्यतेः 'इगुपध–' (सू २८९७) इति कः प्राप्तः। जारभरा। श्वपचा। अनयोः 'कर्मण्यण्' (सू २९१३) प्राप्तः। न्यङ्क्वादिषु पाठाच्छ्वपाकोऽपि। 'यङोऽचि च' (सू २६५०) इति लुक्। 'न धातुलोपे–' (सू २६५६) इति गुणवृद्धिनिषेधः। चेक्रियः। नेन्यः। लोलुवः। पोपुवः। मरीमृजः। चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम्' (वा ३४३०)। आगमस्य दीर्घत्वसामर्थ्यादभ्यासह्रस्वो 'हलादिः शेषः' (सू २१७९) च न। चराचरः। चलाचलः। पतापतः। वदावदः। 'हन्तेर्घत्वं च' (वा ३४३१)। घत्वमभ्यासस्योत्तरस्य तु

'अभ्यासाच्च' (सू २४३०) इति कुत्वम्। घनाघनः। 'पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य' (वा ३४३२)। पाटूपटः। पक्षे चरः। चलः। पतः। वदः। हनः। पाटः। 'रात्रेः कृति-' (सू १००८) इति वा मुम्। रात्रिंचरो रात्रिचरः।

२८९७। इगुपधज्ञाप्रीकिरः कः। ३। १। १३५। एभ्यः कः स्यात्। क्षिपः। लिखः। बुधः। कृशः। ज्ञः। प्रीणातीति प्रियः। किरतीति किरः। वासरूपविधिना ण्वुल्तृचावपि। क्षेपकः-क्षेप्ता।

२८९८। आतश्चोपसर्गे। ३। १। १३६। कः स्यात्। 'श्याद्व्यधा-' (सू २९०३) इति णस्यापवादः। सुग्लः। प्रज्ञः।

२८९९। पाघ्राध्माधेट्दृशः शः। ३। १। १३७। पिबतीति पिबः। जिघ्रः। धमः। धयः। धया कन्या। धेटष्टित्त्वात् 'स्तनंधयी' इति खशीव ङीष्प्राप्तः। 'खशोऽन्यत्र नेष्यते' इति हरदत्तः। पश्यतीति पश्यः। 'घ्रः संज्ञायां न' (वा १९६७)। व्याघ्रादिभिः-'(सू ७३९) इति निर्देशात्।

२९००। अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च। ३। १। १३८। शः स्यात्। लिम्पः। विन्दः। धारयः। पारयः। वेदयः। उदेजयः। चेतयः। सातिः सुखार्थः सौत्रो हेतुमण्ण्यन्तः। सातयः। वासरूपन्यायेन क्विपि सात्परमात्मा। सात्वन्तो भक्ताः। षह मर्षणे चुरादिः। हेतुमण्ण्यन्तो वा। साहयः। 'अनुपसर्गात्' किम्। प्रलिपः। 'नौ लिम्पेर्वाच्यः' (वा १९६८)। निलिम्पा देवाः। 'गवादिषु विन्देः संज्ञायाम्' (वा १९६९)। गोविन्दः। अरविन्दम्।

२९०१। ददातिदधात्योर्विभाषा। ३। १। १३९। शः स्यात्। ददः। दधः। पक्षे वक्ष्यमाणो णः। अनुपसर्गादित्येव। प्रदः। प्रधः।

२९०२। ज्वलितिकसन्तेभ्यो णः। ३। १। १४०। इति शब्द आद्यर्थः। ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा। पक्षेऽच्। ज्वालः-ज्वलः। चालः-चलः। अनुपसर्गादित्येव। उज्ज्वलः। 'तनोतेरुपसंख्यानम्' (वा १९७०)। इहानुपसर्गादिति विभाषेति च न संबध्यते। अवतनोतीत्यवतानः।

२९०३। श्याद्व्यधास्रुसंस्र्वतीणवसावहृलिहश्लिषश्वसश्च। ३। १। १४१। श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात्। श्यैङोऽवस्यतेश्चादन्तत्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम्। अवश्यायः। प्रतिश्यायः। आत्। दायः। धायः। व्याधः। 'स्रु गतौ' आङ्पूर्वः संपूर्वश्च। आस्रावः। संस्रावः। अत्यायः। अवसायः। अवहारः। लेहः। श्लेषः। श्वासः।

२९०४। दुन्योरनुपसर्गे। ३। १। १४२। णः स्यात्। दुनोतीति दावः। नीसाहचर्यात्सानुबन्धकाद्दुनोतेरेव णः। दवतेस्तु पचाद्यच्। दवः। नयतीति नायः। उपसर्गे तु प्रदवः। प्रणयः।

२९०५। विभाषा ग्रहः। ३। १। १४३। णो वा। पक्षेऽच्। व्यवस्थितविभाषेयम्। तेन जलचरे ग्राहः। ज्योतिषि ग्रहः। 'भवतेश्च' इति काशिका। भवो देवः संसारश्च। भावाः पदार्थाः। भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच्। भावः।

२९०६। गेहे कः। ३। १। १४४। गेहे कर्तरि ग्रहेः कः स्यात्। गृह्णाति धान्यादिकमिति गृहम्। तात्स्थ्याद्गृहा दाराः।

२९०७। शिल्पिनि ष्वुन्। ३। १। १४५। क्रियाकौशलं शिल्पं तद्वत्कर्तरि ष्वुन्स्यात्। 'नृतिखनिरञ्जिभ्य एव' (वा १९७१)। नर्तकः-नर्तकी। खनकः-खनकी। 'असि अकेऽने च रञ्जेर्नलोपो वाच्यः' (वा ४०६७)। रजकः-रजकी। भाष्यमते तु नृतिखनिभ्यामेव ष्वुन् रञ्जेस्तु 'कुन्शिल्पिसंज्ञयोः' इत्या इति क्वुन्। टाप्। रजिका। पुंयोगे तु रजकी।

२९०८। गस्थकन्। ३। १। १४६। गायतेस्थकन्स्यात्, शिल्पिनि कर्तरि। गाथकः।

२९०९। ण्युट् च। ३। १। १४७। गायनः। टित्त्वाद्गायनी।

२९१०। हश्च व्रीहिकालयोः। ३। १। १४८। हाको हाङश्च ण्युट् स्यात् व्रीहौ काले च कर्तरि। जहात्युदकमिति हायनो व्रीहिः। जहाति भावानिति हायनो वर्षम्। जिहीते प्राप्नोतीति वा।

२९११। प्रुसृल्वः समभिहारे वुन्। ३। १। १४९। समभिहारग्रहणेन साधुकारित्वं लक्ष्यते। प्रवकः। सरकः। लवकः।

२९१२। आशिषि च। ३। १। १५०। आशीर्विषयार्थवृत्तेर्वुन्स्यात्कर्तरि। जीवतात्-जीवकः। नन्दतात्-नन्दकः। आशीः प्रयोक्तुर्धर्मः। आशासितुः पित्रादेरियमुक्तिः।

२९१३। कर्मण्यण्। ३। २। १। कर्मण्युपपदे धातोरण्प्रत्ययः स्यात्। उपपदसमासः। कुम्भं करोतीति कुम्भकारः। आदित्यं पश्यतीत्यादावनभिधानान्न। 'शीलिकामिभक्ष्याचरिभ्यो णः' (वा १९८०)। अणोऽपवादार्थं वार्तिकम्। मांसशीला। मांसकामा। मांसभक्षा। कल्याणाचारा 'ईक्षिक्षमिभ्यां च' (वा १९८१)। सुखप्रतीक्षा। बहुक्षमा। कथं तर्हि गङ्गाधरभूधरादयः। कर्मणः शेषत्वविवक्षायां भविष्यन्ति।

२९१४। ह्वावामश्च। ३। २। २। अण्स्यात्। कापवादः। स्वर्गह्वायः। तन्तुवायः। धान्यमायः।

२९१५। आतोऽनुपसर्गे कः। ३। २। ३। आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्राणः। 'आतो लोपः'। गोदः। पार्ष्णित्रम्। 'अनुपसर्गे' किम्। गोसंदायः। 'कविधौ सर्वत्र संप्रसारणिभ्यो डः' (वा १९८४)। ब्रह्म जिनाति ब्रह्मज्यः। सर्वत्र ग्रहणादातश्चोपसर्गे आह्वः। प्रह्वः।

२९१६। सुपि स्थः। ३। २। ४। सुपीति योगो विभज्यते। सुप्युपपदे आदन्तात्कः स्यात्। द्वाभ्यां पिबतीति द्विपः। समस्थः। विषमस्थः। ततः 'स्थः'। सुपि तिष्ठतेः कः स्यादारम्भसामर्थ्याद्भावे। आखुनामुत्थानमाखूत्थः।

२९१७। प्रष्ठोऽग्रगामिनि। ८। ३। ९२। प्रतिष्ठत इति प्रष्ठो गौः। अग्रतो गच्छतीत्यर्थः। 'अग्र-' इति किम्। प्रस्थः।

२९१८। अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः। ८। ३। ९७। 'स्थः' इति कप्रत्ययान्तस्यानुकरणम्। षष्ठ्यर्थे प्रथमा। एभ्यः स्थस्य सस्य षः स्यात्। द्विष्ठः। त्रिष्ठः। इत ऊर्ध्वं कर्मणि सुपिति द्वयमप्यनुवर्तते। तत्राकर्मकेषु सुपीत्यस्य संबन्धः।

२९१९। तुन्दशोकयोः परिमृजापनुदोः। ३।२।५। तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात्। 'आलस्यसुखाहरणयोरिति वक्तव्यम्' (वा १९८८)। तुन्दं परिमार्ष्टीति तुन्दपरिमृजोऽलसः। शोकापनुदः। सुखस्याहर्ता। अलसादन्यत्र तुन्दपरिमार्ज एव। यस्तु संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः। 'कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्' (वा १९८९)। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणोऽयम्। महीध्रः। कुध्रः। गिलतीति गिलः।

२९२०। प्रे दाज्ञः। ३।२।६। दारूपाज्ज्ञानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यादणोऽपवादः। सर्वप्रदः। पथिप्रज्ञः। अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सुपि न कः। गोसंप्रदायः।

२९२१। खामि ख्यः। ३।२।७। गोसंख्यः।

२९२२। गापोष्टक्। ३।२।८। अनुपसृष्टाभ्यामाभ्यां टक्स्यात्कर्मण्युपपदे। सामगः–सामगी। उपसर्गे तु सामसंगायः। 'पिबतेः सुराशीध्वोरिति वाच्यम्' (वा १९९०)। सुरापी। शीधुपी। अन्यत्र क्षीरपा ब्राह्मणी। सुरां पाति रक्षतीति सुरापा।

२९२३। हरतेरनुद्यमनेऽच्। ३।२।९। अंशहरः। 'अनुद्यमने' किम्। भारहारः। 'शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुःषु ग्रहेरुपसंख्यानम्' (वा १९९२) शक्तिग्रहः। लाङ्गलग्रहः। 'सूत्रे च धार्यर्थे' (वा १९९३) सूत्रग्रहः। यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव। सूत्रग्राहः।

२९२४। वयसि च ३।२।१०। उद्यमनार्थं सूत्रम्। कवचहरः कुमारः।

२९२५। आङि ताच्छील्ये। ३।२।११। पुष्पाण्याहरति तच्छीलः पुष्पाहरः। 'ताच्छील्ये' किम्। भाराहारः।

२९२६। अर्हः। ३।२।१२। अर्हतेरच्स्यात्कर्मण्युपपदेऽणोपवादः। पूजार्हा ब्राह्मणी।

२९२७। स्तम्बकर्णयो रमिजपोः। ३।२।१३। 'हस्तिसूचकयोरिति वक्तव्यम्' (वा १९९४)। स्तम्बे रमते स्तम्बेरमो हस्ती। 'तत्पुरुषे कृति–' (सू ९७२) इति 'हलदन्तात्–' (सू ९६६) इति वा ङेरलुक्। कर्णेजपः सूचकः।

२९२८। शमि धातोः संज्ञायाम्। ३।२।१४। शंभवः। शंवदः। पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम्। कृञो हेत्वादिषु टो मा भूत्। शंकरा नाम परिव्राजिका तच्छीला।

२९२९। अधिकरणे शेतेः। ३।२।१५। खे शेते खशयः। 'पार्श्वादिषूपसंख्यानम्' (वा १९९६)। पार्श्वाभ्यां शेते पार्श्वशयः। पृष्ठशयः। उदरेण शेते उदरशयः। 'उत्तानादिषु कर्तृषु' (वा १९९८)। उत्तानः शेते उत्तानशयः। अवमूर्धशयः। अवनतो मूर्धा यस्य सोऽवमूर्धा। अधोमुखः शेत इत्यर्थः। 'गिरौ डश्छन्दसि' (वा १९९९) गिरौ शेते गिरिशः। कथं तर्हि 'गिरिशमुपचचार प्रत्यहं सा सुकेशी' इति। गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः।

२९३०। चरेष्टः। ३।२।१६। अधिकरण उपपदे। कुरुचरः। कुरुचरी।

२९३१। भिक्षासेनादायेषु च। ३।२।१७। भिक्षां चरतीति भिक्षाचरः। सेनाचरः।

आदायेति ल्यबन्तम् आदायचरः । कथम् 'प्रेक्ष्य स्थितां सहचरीम्' इति । पचादिषु चरडिति पाठात् ।

२९३२ । पुरोऽग्रतोऽग्रेषु सर्तेः । ३ । २ । १८ । पुरःसरः । अग्रतः सरः । अग्रमग्रेणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्र इत्येदन्तत्वमपि निपात्यते । कथं तर्हि 'यूथं तदग्रसरगर्वितकृष्णसारम्' इति । बाहुलकादिति हरदत्तः ।

२९३३ । पूर्वे कर्तरि । ३ । २ । १९ । कर्तृवाचिनि पूर्वशब्द उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ।

२९३४ । कृञो हेतुताच्छील्यानुलोम्येषु । ३ । २ । २० । एषु द्योत्येषु करोतेष्टः स्यात् । 'अतः कृकमि–' (सू १६०) इति सः । यशस्करी विद्या । श्राद्धकरः । वचनकरः ।

२९३५ । दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु । ३ । २ । २१ । एषु कृञष्टः स्यात् हेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । 'नित्यं समासेऽनुत्तरपदस्थस्य' (सू १५९) इति षत्वम् । धनुष्करः । अरुष्करः । 'किंयत्तद्बहुषु कृञोऽज्विधानम्' (वा २००२) । इति वार्तिकम् । किंकरा । यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वादच् । पुंयोगे ङीष् । किंकरी ।

२९३६ । कर्मणि भृतौ । ३ । २ । २२ । कर्मशब्द उपपदे करोतेष्टः स्याद्भृतौ । कर्मकरो भृतकः । कर्मकारोऽन्यः ।

२९३७ । न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु । ३ । २ । २३ । एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ।

२९३८ । स्तम्बशकृतोरिन् । ३ । २ । २४ । 'व्रीहिवत्सयोरिति वक्तव्यम्' (वा २००३) स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । 'व्रीहिवत्सयोः' किम् । स्तम्बकारः । शकृत्कारः ।

२९३९ । हरतेर्दृतिनाथयोः पशौ । ३ । २ । २५ । दृतिनाथयोरुपपदयोर्हृञ इन्स्यात् पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः । 'पशौ' किम् । दृतिहरः । नाथहरः ।

२९४० । फलेग्रहिरात्मंभरिश्च । ३ । २ । २६ । फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मंभरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिंभरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । 'ज्योत्स्ना करम्भमुदरंभरयश्चकोराः' इति मुरारिः ।

२९४१ । एजेः खश् । ३ । २ । २८ । ण्यन्तादेजेः खश् स्यात् ।

२९४२ । अरुर्द्विषदजन्तस्य मुम् । ६ । ३ । ६७ । अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्त उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादिः । जनमेजयतीति जनमेजयः । 'वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम्' (वा २००९) वातमजा मृगाः ।

२९४३ । खित्यनव्ययस्य । ६ । ३ । ६६ । खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यात्

ततो मुम् । शुनिंधयः । तिलंतुदः । शर्धंजहा माषाः । शर्धोपानशब्दस्तं जहातीति विग्रहः । जहातिरन्तर्भावितण्यर्थः ।

२९४४ । नासिकास्तनयोर्ध्माधेटोः । ३ । २ । २९ । अत्र वार्तिकम्—'स्तने धेटो नासिकायां ध्मश्चेति वाच्यम्' (वा २००६–७) । स्तनं धयतीति स्तनंधयः । धेटष्टित्त्वा-स्तनंधयी । नासिकंधमः । नासिकंधयः ।

२९४५ । नाडीमुष्ट्योश्च । ३ । २ । ३० । एतयोरुपपदयोः कर्मणोर्ध्माधेटोः खश् स्यात् । 'यथासंख्यं नेष्यते' । नाडिंधमः—नाडिंधयः । मुष्टिंधमः—मुष्टिंधयः । 'घटीखारीखरीषूप-संख्यानम्' (वा २००८) । घटिंधमः—घटिंधय इत्यादि । खारी परिमाणविशेषः । खरी गर्दभी ।

२९४६ । उदिकूले रुजिवहोः । ३ । २ । ३१ । उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्यु-पपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ।

२९४७ । वहाभ्रे लिहः । ३ । २ । ३२ । वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदा-दित्वाच्छपो लुक् । खशो ङित्त्वान्न गुणः । अभ्रंलिहो वायुः ।

२९४८ । परिमाणे पचः । ३ । २ ३३ । प्रस्थंपचा स्थाली । खारींपचः कटाहः ।

२९४९ । मितनखे च । ३ । २ । ३४ । मितंपचा ब्राह्मणी । नखंपचा यवागूः । पचिरत्र तापवाची ।

२९५० । विध्वरुषोस्तुदः । ३ । २ । ३५ । विधुंतुदः । मुमि कृते संयोगान्तस्य लोपः । अरुंतुदः ।

२९५१ । असूर्यललाटयोर्दृशितपोः । ३ । २ । ३६ । असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यंपश्या राजदाराः । ललाटंतपः सूर्यः ।

२९५२ । उग्रंपश्येरंमदपाणिंधमाश्च । ३ । २ । ३७ । एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरोदकं तेन माद्यति दीप्यतेऽविन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात्श्यन्न । पाणयो ध्मायन्ते ऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकारावावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयः शब्द्यन्ते ।

२९५३ । प्रियवशे वदः खच् । ३ । २ । ३८ । प्रियंवदः । वशंवदः । 'गमेः सुपि वाच्यः' (वा २००९) असंज्ञार्थमिदम् । मितंगमो हस्ती । 'विहायसो विह इति वाच्यम्' (वा २०१०) । 'खच डिद्वा वाच्यः' (वा २०११) । विहंगमः—विहंगः । भुजंगमः—भुजंगः ।

२९५४ । द्विषत्परयोस्तापेः । ३ । २ । ३९ । खच्स्यात् ।

२९५५ । खचि ह्रस्वः । ६ । ४ । ९४ । खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषंतपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषानित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ।

२९५६ । वाचि यमो व्रते । ३ । २ । ४० । वाक्यशब्द उपपदे यमेः खच्स्याद्व्रते गम्ये ।

२९५७ । वाचंयमपुरंदरौ च । ६ । ३ । ६९ । वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । 'व्रते' किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ।

२९५८। पूःसर्वयोर्दारिसहोः। ३। २। ४१। पुरं दारयतीति पुरंदरः। सर्वंसहः। सहिग्रहणमसंज्ञार्थम्। 'भगे च दारेः' (वा २०१३) इति काशिका। बाहुलकेन लब्धमिदमित्याहुः। भगं दारयतीति भगंदरः।

२९५९। सर्वकूलाभ्रकरीषेषु कषः। ३। २। ४२। सर्वंकषः खलः। कूलंकषा नदी अभ्रंकषो वायुः। करीषंकषा वात्या।

२९६०। मेघर्तिभयेषु कृञः। ३। २। ४३। मेघंकरः। ऋतिंकरः। भयंकरः। भयशब्देन तदन्तविधिः। अभयंकरः।

२९६१। क्षेमप्रियमद्रेऽण्च। ३। २। ४४। एषु कृञोऽण्स्यात्। चात्खच्। क्षेमंकरः–क्षेमकारः। प्रियंकरः–प्रियकारः। मद्रंकरः–मद्रकारः। वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति। कथं तर्हि 'अल्पारम्भः क्षेमंकरः' इति। कर्मणः शेषत्वविवक्षायां पचाद्यच्।

२९६२। आशिते भुवः करणभावयोः। ३। २। ४५। आशितशब्द उपपदे भवतेः खच्। आशितो भवत्यनेनाशितंभव ओदनः। आशितस्य भवनमाशितंभवः।

२९६३। संज्ञायां भृतॄवृजिधारिसहितपिदमः। ३। २। ४६। विश्वं बिभर्तीति विश्वंभरः। विश्वंभरा। रथंतरं साम। इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः। पतिंवरा कन्या। शत्रुंजयो हस्ती। युगंधरः पर्वतः। शत्रुंतपः। शत्रुंसहः। अरिंदमः। दमिः शमनायां, तेन सकर्मक इत्युक्तम्। मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः।

२९६४। गमश्च। ३। २। ४७। सुतंगमः।

२९६५। अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः। ३। २। ४८। संज्ञायामिति निवृत्तम्। एषु गमेर्डः स्यात्। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। अन्तं गच्छतीत्यन्तग इत्यादि। 'सर्वत्रपन्नयोरुपसंख्यानम्' (वा२०१४)। सर्वत्रगः। पन्नं पतितं गच्छतीति पन्नगः। पन्नमिति पर्यतः क्तान्तं क्रियाविशेषणम्। 'उरसो लोपश्च' (वा२०१५)। उरसा गच्छतीत्युरगः। 'सुदुरोरधिकरणे' (वा२०१६)। सुखेन गच्छत्यत्र सुगः। दुर्गः। 'अन्यत्रापि दृश्यत इति वक्तव्यम्' (वा२०१८)। ग्रामगः। 'डे च विहायसो विहादेशो वक्तव्यः' (वा२०१२)–विहगः।

२९६६। आशिषि हनः। ३। २। ४९। शत्रुं वध्याच्छत्रुहः। 'आशिषि' किम्। शत्रुघातः 'दारावाहनोऽणन्तस्य च टः संज्ञायाम्' (वा२०१९)। दारुशब्द उपपदे आङ्पूर्वाद्धन्तेरण्टकारश्चान्तादेशो वक्तव्य इत्यर्थः। दार्वाघाटः। 'चारौ वा' (वा२०२०)। चार्वाघाटः। चार्वाघातः। 'कर्मणि समि च' (वा२०२२)। कर्मण्युपपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः। वर्णान्संहन्तीति वर्णसंघाटः। पदसंघाटः। वर्णसंघातः। पदसंघातः।

२९६७। अपे क्लेशतमसोः। ३। २। ५०। अपपूर्वाद्धन्तेर्डः स्यात्। अनाशीरर्थमिदम्। क्लेशापहः पुत्रः। तमोऽपहः सूर्यः।

२९६८। कुमारशीर्षयोर्णिनिः। ३। २। ५१। कुमारघाती। शिरसः शीर्षभावो निपात्यते शीर्षघाती।

२९६९। लक्षणे जायापत्योष्टक्। ३। २। ५२। हन्तेष्टक्स्याल्लक्षणवति कर्तरि। जायाघ्नो ना। पतिघ्नी स्त्री।

२९७० । अमनुष्यकर्तृके च ३ । २ । ५३ । जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा। पित्तघ्नं घृतम् । 'अमनुष्य–' इति किम् । आखुघातः शूद्रः । अथ कथं 'बलभद्रः प्रलम्बघ्नः' 'शत्रुघ्नः' 'कृतघ्नः' इत्यादि । मूलविभुजादित्वात्सिद्धम् । चोरघातो नगरघातो हस्तीति तु बाहुलकादणि ।

२९७१ । शक्तौ हस्तिकवाटयोः । ३ । २ । ५४ । हन्तेष्टक्स्याच्छक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कवाटघ्नश्चोरः । कपाटेति पाठान्तरम् ।

२९७२ । पाणिघताडघौ शिल्पिनि । ३ । २ । ५५ । हन्तेष्टक्टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । 'शिल्पिनि' किम् । पाणिघातः । ताडघातः । 'राजघ उपसंख्यानम्' (वा २० २२) । राजानं हन्ति राजघः ।

२९७३ । आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् । ३ । २ । ५६ । एषु च्व्यर्थेष्वच्व्यन्तेषु कर्मसूपपदेषु कृञः ख्युन्स्यात् । अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम् । 'अच्वौ' किम् । आढ्यीकुर्वन्त्यनेन । इह प्रतिषेधसामर्थ्याल्ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ।

२९७४ । कर्तरि भुवः खिष्णुच्खुकञौ । ३ । २ । ५७ । आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आढ्यो भवतीति आढ्यंभविष्णुः । आढ्यंभावुकः । 'स्पृशोऽनुदके क्विन्' (सू ४३२) । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च' (सू ३७३) व्याख्यातम् । 'त्यदादिषु दृशोऽनालोचने कञ्च' (सू ४२९) । 'समानान्ययोश्चेति वाच्यम्' (वा २०२९) । सदृक्–सदृशः । अन्यादृक्–अन्यादृशः । 'क्सोऽपि वाच्यः' (वा २०३०) । तादृक्षः । सदृक्षः । अन्यादृक्षः ।

२९७५ । सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् । ३ । २ । ६१ । एभ्यः क्विप्स्यादुपसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि । 'अग्रग्रामाभ्यां नयतेर्णो वाच्यः' (वा ५०६४) । अग्रणीः । ग्रामणीः ।

२९७६ । भजो ण्विः । ३ । २ । ६२ । सुप्युपसर्गे चोपपदे भजेर्ण्विः स्यात् । अंशभाक् । प्रभाक् ।

२९७७ । अदोऽनन्ने । ३ । २ । ६८ । विट् स्यात् । आममत्ति आमात् । सस्यात् । 'अनन्ने' किम् । अन्नादः ।

२९७८ । क्रव्ये च । ३ । २ । ६९ । अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् । आममांसभक्षकः । कथं तर्हि 'क्रव्यादोऽस्रप आसुरः' इति । पक्वमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ।

२९७९ । दुहः कब्घश्च । ३ । २ । ७० । कामदुघा ।

---

१ 'पूर्वपदात्संज्ञायामगः' (सू८५८) इति सूत्रेणेति भावः । अपूर्ववचनत्वे तु 'ग्रामनयनस्य' इति ग्रन्थविरोधः ।

२९८० । अन्येभ्योऽपि दृश्यन्ते । ३ । २ । ७५ । छन्दसीति निवृत्तम् । मनिन्क्वनिब्वनिब्विच् एते प्रत्यया धातोः स्युः ।

२९८१ । नेड्वशि कृति । ७ । २ । ८ । वशादेः कृत इण्न स्यात् । शॄ । सुशर्मा । प्रातरित्वा ।

२९८२ । विड्वनोरनुनासिकस्यात् । ६ । ४ । ४१ । अनुनासिकस्यात्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । सेट् । रेट् । सुगण् ।

२९८३ । क्विप् च । ३ । २ । ७६ । अयमपि दृश्यते । 'सत्सूद्विष–' (सू २९७५) इति त्वस्यैव प्रपञ्चः । उखास्रत् । पर्णध्वत् । वाहभ्रट् ।

२९८४ । अन्तः । ८ । ४ । २० । पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् । 'शास इत्–' (सू २४८६) इतीत्वम् । मित्राणि शास्ति मित्रशीः । 'आशासः क्वौ उपधाया इत्त्वं वाच्यम्' (वा ४०७०) । आशीः । इत्त्वोत्वे । गीः । पूः ।

२९८५ । इस्मन्त्रन्क्विषु च । ६ । ४ । ९७ । एषु छादेर्ह्रस्वः स्यात् । तनुच्छत् । 'अनुनासिकस्य क्वि–' (सू २६६६) इति दीर्घः । 'मो नो धातोः' (सू ३४१) । प्रतान् । प्रशान् । 'च्छ्वोः–' (सू २५६१) इत्यूठ् । अक्षद्यूः । 'ज्वरत्वर–' (सू २६५४) इत्यूठ् । जूः । जुरौ । जुरः । तूः । स्रूः । ऊठ् । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्वः । 'राल्लोपः' (सू २६५५) । मूर्छा । मूः । मुरौ । मुरः । धुर्वी । धूः ।

२९८६ । गमः क्वौ । ६ । ४ । ४० । अनुनासिकलोपः स्यात् । अङ्गगत् । 'गमादीनामिति वक्तव्यम्' (वा ४०७३) । परीतत् । संयत् । सुनत् । 'ऊङ् च गमादीनामिति वक्तव्यं लोपश्च' (वा ४०७३–७४) । अग्रेगूः । अग्रेभ्रूः ।

२९८७ । स्थः क च । ३ । २ । ७७ । चात्क्विप् । शंस्थः शंस्थाः । 'शमिधातोः–' (सू २९२८) इत्यचं बाधितुं सूत्रम् ।

२९८८ । सुप्यजातौ णिनिस्ताच्छील्ये । ३ । २ । ७८ । अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । 'अजातौ' किम् । ब्राह्मणानामन्त्रयिता । 'ताच्छील्ये' किम् । उष्णं भुङ्क्ते कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवादिभिश्च तदेवानुसृतम् । एतच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । 'स बभूवोपजीविनाम्' 'अनुयायिवर्गः' । 'पतत्यधो धाम विसारि' । 'न वञ्चनियाः प्रभवोऽनुजीविभिः' इत्यादौ । 'साधुकारिण्युपसंख्यानम्' (वा २०३८) 'ब्रह्मणि वदः' (वा २०३९) अताच्छील्यार्थं वार्तिकद्वयम् । साधुदायी । ब्रह्मवादी ।

२९८९ । कर्तर्युपमाने । ३ । २ । ७९ । णिनिः स्यात् । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थं जात्यर्थं च सूत्रम् । 'कर्तरि' किम् । अपूपानिव भक्षयति माषान् । 'उपमाने' किम् । उष्ट्रः क्रोशति ।

२९९० । व्रते । ३ । २ । ८० । णिनिः स्यात् । स्थण्डिलशायी ।

२९९१ । बहुलमाभीक्ष्ण्ये । ३ । २ । ८१ । पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ।
२९९२ । मनः । ३ । २ । ८२ । सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ।
२९९३ । आत्ममाने खश्च । ३ । २ । ८३ । स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् । चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । 'खित्यनव्ययस्य' (सू २९४३) । कालिंमन्या । 'अनव्ययस्य' किम् । दिवामन्या ।
२९९४ । इच एकाचोऽम्प्रत्ययवच्च । ६ । ३ । ६८ । इजन्तादेकाचोऽम्स्यात्स च स्वाद्यम्वत्खिदन्ते परे । 'औतोऽम्शसोः' (सू २८९) गांमन्यः । 'वाम्शसोः' (सू ३०२) । श्रियंमन्यः । स्त्रींमन्यः । नृ । नरंमन्यः । भुवंमन्यः । 'श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनाच्छ्रीशब्दस्य ह्रस्वो मुममोरभावश्च ।
२९९५ । भूते । ३ । २ । ८४ । अधिकारोऽयम् । 'वर्तमाने लट्' (सू २१९१) इति यावत् ।
२९९६ । करणे यजः । ३ । २ । ८५ । करण उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनेष्टवान्सोमयाजी । अग्निष्टोमयाजी ।
२९९७ । कर्मणि हनः । ३ । २ । ८६ । पितृव्यघाती । कर्मणीत्येतत् 'सहे च' (सू३००६) इति यावदधिक्रियते ।
२९९८ । ब्रह्मभ्रूणवृत्रेषु क्विप् । ३ । २ । ८७ । एषु कर्मसूपपदेषु हन्तेर्भूते क्विप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । 'क्विप्च' (सू २९८३) इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव, हन्तेरेव, भूत एव, क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव क्विबेवेति द्विविधो नियम इति भाष्यम् ।
२९९९ । सुकर्मपापमन्त्रपुण्येषु कृञः । ३ । २ । ८९ । सुकर्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न क्विप् । भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न क्विप् । स्वादिष्वेवेतिनियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्रकृत् । भाष्यकृत् ।
३००० । सोमे सुञः । ३ । २ । ९० । सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ।
३००१ । अग्नौ चेः । ३ । २ । ९१ । अग्निचित् ।
३००२ । कर्मण्यग्न्याख्यायाम् । ३ । २ । ९२ । कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ।
३००३ । कर्मणीनिविक्रियः । ३ । २ । ९३ । कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् । 'कुत्सितग्रहणं कर्तव्यम्' (वा २०४७) । सोमविक्रयी । घृतविक्रयी ।
३००४ । दृशेः क्वनिप् । ३ । २ । ९४ । कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ।
३००५ । राजनि युधिकृञः । ३ । २ । ९५ । क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान्राजयुध्वा । राजकृत्वा ।

३००६ । सहे च । ३ । २ । ९६ । कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ।

३००७ । सप्तम्यां जनेर्डः । ३ । २ । ९७ । सरसिजम् । मन्दुरायां जातो मन्दुरजः । 'ङ्यापोः–' (सू १००१) इति ह्रस्वः ।

३००८ । पञ्चम्यामजातौ । ३ । २ । ९८ । जातिशब्दवर्जिते पञ्चम्यन्त उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ।

३००९ । उपसर्गे च संज्ञायाम् । ३ । २ । ९९ । 'प्रजा स्यात्संततौ जने' ।

३०१० । अनौ कर्मणि । ३ । २ । १०० । अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ।

३०११ । अन्येष्वपि दृश्यते । ३ । २ । १०१ । अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तरेष्वपि क्वचित् । परितः खाता परिखा ।

३०१२ । क्तक्तवतू निष्ठा । १ । १ । २६ । एतौ निष्ठासंज्ञौ स्तः ।

३०१३ । निष्ठा । ३ । २ । १०२ । भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र 'तयोरेव–' (सू २८३३) इति भावकर्मणोः क्तः । 'कर्तरि कृत्' (सू २८३२) इति कर्तरि क्तवतुः । उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ।

३०१४ । निष्ठायामण्यदर्थे । ६ । ४ । ६० । ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ।

३०१५ । क्षियो दीर्घात् । ८ । २ । ४६ । दीर्घात्क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । 'श्र्युकः किति' (सू २३८१) । श्रितः–श्रितवान् । भूतः–भूतवान् । क्षुतः । 'ऊर्णोतेर्णुवद्भावो वाच्यः' (वा १७९२) । तेन एकाच्त्वान्नेट् । ऊर्णुतः । नुतः । वृतः ।

३०१६ । रदाभ्यां निष्ठातो नः पूर्वस्य च दः । ८ । २ । ४२ । रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शॄ । 'ॠत इत्–' (सू २३९०) । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ।

३०१७ । संयोगादेरातो धातोर्यण्वतः । ८ । २ । ४३ । निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः ।

३०१८ । ल्वादिभ्यः । ८ । २ । ४४ । एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या । 'ग्रहिज्या' (सू २४१२) । जीनः । 'दुग्वोर्दीर्घश्च' (वा ४८३२) । 'दु गतौ' । दूनः । 'टुदु उपतापे' इत्ययं तु न गृह्यते सानुबन्धकत्वात् । 'मृदुतया दुतया' इति माघः । गूनः । 'पूञो विनाशे' (वा ४८३३) । पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् । 'सिनोतेर्ग्रासकर्मकर्तृकस्य' (वा ४८३४) । सिनो ग्रासः । 'ग्रास' इति किम् । सिता पाशेन सूकरी । 'कर्मकर्तृक–' इति किम् । सितो ग्रासो देवदत्तेन ।

३०१९ । ओदितश्च । ८ । २ । ४५ । भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । 'स्वादय ओदितः' (गण) इत्युक्तम् । सूनः–सूनवान् । दूनः– दूनवान् । ओदिन्मध्ये डीङः पाठसामर्थ्यान्नेट् उड्डीनः ।

३०२०। द्रवमूर्तिस्पर्शयोः श्यः। ६। १। २४। द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम्।

३०२१। श्योऽस्पर्शे। ८। २। ४७। श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे। 'हलः' (सू २५५९) इति दीर्घः। शीनं घृतम्। 'अस्पर्शे' किम्। शीतं जलम्। 'द्रवमूर्तिस्पर्शयोः' किम्। संश्यानो वृश्चिकः शीतात्संकुचित इत्यर्थः।

३०२२। प्रतेश्च। ६। १। २५। प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम्। प्रतिशीनः।

३०२३। विभाषाभ्यवपूर्वस्य। ६। १। २६। श्यः संप्रसारणं वा स्यात्। अभिश्यानं अभिशीनम् घृतम्। अवश्यानोऽवशीनो वृश्चिकः। व्यवस्थितविभाषेयम्। तेनेह न। समवश्यानः।

३०२४। अञ्चोऽनपादाने। ८। २। ४८। अञ्चो निष्ठातस्य नः स्यान्न त्वपादाने।

३०२५। यस्य विभाषा। ७। २। १५। यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात्। 'उदितो वा' (सू ३३२८) इति क्त्वायां वेट्त्वादिह नेट्। समक्नः। 'अनपादाने' किम्। उदक्तमुदकं कूपात्। नत्वस्यासिद्धत्वात् 'व्रश्च–' (सू २९४) इति षत्वे प्राप्ते। 'निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः' (वा ४७७३)। वृक्णः। वृक्णवान्।

३०२६। परिस्कन्दः प्राच्यभरतेषु। ८। ३। ७५। पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते। परिस्कन्दः। 'प्राच्य–' इति किम्। परिष्कन्दः–परिस्कन्दः। 'परेश्च' (सू २३९९) इति विकल्पः। 'स्तन्भेः' (सू २२७२) इति षत्वे प्राप्ते।

३०२७। प्रतिस्तब्धनिस्तब्धौ च। ८। ३। ११४। अत्र षत्वं न स्यात्।

३०२८। दिवोऽविजिगीषायाम्। ८। ३। ४९। दिवो निष्ठातस्य नः स्यादविजिगीषायाम्। द्यूनः। विजिगीषायां तु। द्यूतम्।

३०२९। निर्वाणोऽवाते। ८। २। ५०। अवात इति च्छेदः। निपूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातश्चेत्कर्ता न। निर्वाणोऽग्निर्मुनिर्वा। वाते तु निर्वातो वातः।

३०३०। शुषः कः। ८। २। ५१। निष्ठात इत्येव। शुष्कः।

३०३१। पचो वः। ८। २। ५२। पक्वः।

३०३२। क्षायो मः। ८। २। ५३। क्षामः।

३०३३। स्त्यः प्रपूर्वस्य। ६। १। २३। प्रात्स्त्यः संप्रसारणं स्यान्निष्ठायाम्।

३०३४। प्रस्त्योऽन्यतरस्याम्। ८। २। ५४। निष्ठातस्य मो वा स्यात्। प्रस्तीमः–प्रस्तीतः। 'प्रात्' किम्। स्त्यानः।

३०३५। अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः। ८। २। ५५। ञिफला। फुल्लः। निष्ठातस्य लत्वं निपात्यते। क्तवत्वेकदेशस्यापीदं निपातनमिष्यते। फुल्लवान्। क्षीबादिषु तु क्तप्रत्ययस्यैव तलोपः। तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते। क्षीबो मत्तः। कृशस्तनुः। उल्लाघो नीरोगः। 'अनुपसर्गात्' किम्।

३०३६। आदितश्च। ७। २। १६। आकारेतो निष्ठाया इण्न स्यात्।

३०३७। ति च। ७। ४। ८९। चरफलोरत उत्स्यात्तादौ किति। प्रफुल्तः। प्रक्षीबितः। प्रकृशितः। प्रोल्लाघितः। कथं तर्हि 'लोध्रद्रुमं सानुमतः प्रफुल्लम्' इति। 'फुल्ल विक-

सने' पचाद्यच् । सूत्रं तु फुल्लादिनिवृत्त्यर्थम् । 'उत्फुल्लसंफुल्लयोरुपसंख्यानम्' (वा ४८४३) ।

३०३८ । नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् । ८ । २ । ५६ । एभ्यो निष्ठातस्य नो वा । नुन्नः-नुत्तः । 'विद' विचारणे रौधादिक एव गृह्यते । उन्दिना परेण साहचर्यात् । विन्नः-वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ।

३०३९ । श्वीदितो निष्ठायाम् । ७ । २ । १४ । श्वयतेरीदितश्च निष्ठाया इण्न । उन्नः-उत्तः । त्राणः-त्रातः । घ्राणः-घ्रातः । ह्रीणः-ह्रीतः ।

३०४० । न ध्याख्यापृमूर्च्छिमदाम् । ८ । २ । ५७ । एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः । 'राल्लोपः' । मूर्तः । मत्तः ।

३०४१ । वित्तो भोगप्रत्यययोः । ८ । २ । ५८ । विन्दतेर्निष्ठान्तस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । 'अनयोः' किम् । विन्नः । 'विभाषा गमहन-' (सू ३०९९) इति क्वसौ वेट्त्वादिह नेट् ।

३०४२ । भित्तं शकलम् । ८ । २ । ५९ । भिन्नमन्यत् ।

३०४३ । ऋणमाधमर्ण्ये । ८ । २ । ६० । ऋधातोः क्ते तकारस्य नत्वं निपात्यते आधमर्ण्यव्यवहारे । ऋतमन्यत् ।

३०४४ । स्फायः स्फी निष्ठायाम् । ६ । १ । २२ । स्फीतः ।

३०४५ । इण्निष्ठायाम् । ७ । २ । ४७ । निरः कुषो निष्ठाया इट् स्यात् । 'यस्य विभाषा' (सू ३०२५) इति निषेधे प्राप्ते पुनर्विधिः निष्कुषितः ।

३०४६ । वसतिक्षुधोरिट् । ७ । २ । ५२ । आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ।

३०४७ । अञ्चेः पूजायाम् । ७ । २ । ५३ । पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात् । अञ्चितः । गतौ त्वक्तः ।

३०४८ । लुभो विमोहने । ७ । २ । ५४ । लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्न तु गार्ध्ये । लुभितः । गार्ध्ये तु लुब्धः ।

३०४९ । क्लिशः क्त्वानिष्ठयोः । ७ । २ । ५० । इड्वा स्यात् । 'क्लिश उपतापे' (अस्य) नित्यं प्राप्ते 'क्लिशू विबाधने' अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते, विकल्पः । क्लिशितः-क्लिष्टः ।

३०५० । पूङश्च । ७ । २ । ५१ । पूङः क्त्वानिष्ठयोरिड्वा स्यात् ।

३०५१ । पूङः क्त्वा च । १ । २ । २२ । पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः-पूतः । क्त्वाग्रहणमुत्तरार्थम् । 'नोपधात्-' (सू ३३२४) इत्यत्र हि क्त्वैव संबध्यते ।

३०५२ । निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः । १ । २ । १९ । एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः-शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थः । शेश्यितः-शेश्यितवान् । 'आदिकर्मणि निष्ठा वक्तव्या' (वा २०५१) ।

३०५३ । आदिकर्मणि क्तः कर्तरि च । ३ । ४ । ७१ । आदिकर्मणि यः क्तः स कर्तरि स्यात् । चाद्भावकर्मणोः ।

३०५४ । विभाषा भावादिकर्मणोः । ७ । २ । १७ । भाव आदिकर्मणि चादितो

निष्ठाया इड्वा स्यात्। प्रस्वेदितश्चैत्रः। प्रस्वेदितं तेन। 'ञिष्विदा' इति भ्वादिरत्र गृह्यते ञीद्भिः साहचर्यात्। स्विद्यतेस्तु स्विदित इत्येव। 'ञिमिदा' 'ञिक्ष्विदा' दिवादी भ्वादी च। प्रमेदितः-प्रमेदितवान्। प्रक्ष्वेदितः-प्रक्ष्वेदितवान्। प्रधर्षितः-प्रधर्षितवान्। धर्षितं तेन। 'सेट्' किम्। प्रास्विन्नः। प्रास्विन्नं तेनेत्यादि।

३०५५। मृषस्तितिक्षायाम्। १। २। २०। सेण्निष्ठा किन्न स्यात्। मर्षितः-मर्षितवान्। 'क्षमायाम्' किम्। अपमृषितं वाक्यम्। अविस्पष्टमित्यर्थः।

३०५६। उदुपधाद्भावादिकर्मणोरन्यतरस्याम्। १। २। २१। उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात्। द्युतितम्-द्योतितम्। मुदितम्-मोदितं साधुना। प्रद्युतितः-प्रद्योतितः। प्रमुदितः-प्रमोदितः साधुः। 'उदुपधात्' किम्। विदितम्। 'भावा-' इत्यादि किम्। रुचितं कार्षापणम्। 'सेट्' किम्। कुष्टम्। 'शब्विकरणेभ्य एवेष्यते' (वा ६३६)। नेह। गुध्यतेर्गुधितम्।

३०५७। निष्ठायां सेटि। ६। ४। ५२। णेर्लोपः स्यात्। भावितः-भावितवान्। 'श्वीदितः-' (सू ३०३९) इति नेट्। संप्रसारणम्। शूनः। दीप्तः। गुहू। गूढः। वनु। वतः। तनु। ततः। पतेः सनि वेड्कत्वादिडभावे प्राप्ते 'द्वितीया श्रित-' (सू ६८६) इति सूत्रे निपातनादिट्। पतितः। 'सेऽसिचि' (सू २५०६) इति वेड्कत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा। तेन 'धावितमिभराजधिया' इत्यादि। 'यस्यविभाषा' (सू ३०३९) इत्यत्रैकाच इत्येव। दरिद्रितः।

३०५८। क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः सक्ताविस्पष्टस्वरानायासभृशेषु। ७। २। १८। क्षुब्धादीन्यष्टावनिड्कानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु। द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः। मन्थनदण्डश्च। क्षुब्धो मन्थश्चेत्। स्वान्तं मनः। ध्वान्तं तमः। लग्नं सक्तम्। निष्ठानत्वमपि निपातनात्। म्लिष्टमविस्पष्टम्। विरिब्धः स्वरः। 'म्लेच्छ' 'रेभृ' अनयोरुपधाया इत्त्वमपि निपात्यते। फाण्टमनायाससाध्यः कषायविशेषः। माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्य आह। बाढं भृशम्। अन्यत्र तु क्षुभितम्। क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात्। स्वनितम्। ध्वनितम्। लगितम्। म्लेच्छितम्। विरेभितम्। फणितम्। वाहितम्।

३०५९। धृषिशसी वैयात्ये। ७। २। १९। एतौ निष्ठायामविनय एवानिटौ स्तः। धृष्टः। विशस्तः। अन्यत्र धर्षितः। विशसितः। भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति। अतएव नियमार्थमिदं सूत्रमिति वृत्तिः। धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः। माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह। धृष्टम्-धर्षितम्। प्रधृष्टः-प्रधर्षितः।

३०६०। दृढः स्थूलबलयोः। ७। २। २०। स्थूले बलवति च निपात्यते। 'दृह दृहि वृद्धौ'। क्तस्येडभावः। तस्य ढत्वम्। हस्य लोपः। इदितो नलोपश्च। दृहितः-दृंहितोऽन्यः।

३०६१। प्रभौ परिवृढः। ७। २। २१। 'वृह वृहि वृद्धौ'। निपातनं प्राग्वत्। परिवृहितः-परिवृंहितोऽन्यः।

३०६२। कृच्छ्रगहनयोः कषः। ७। २। २२। कषो निष्ठाया इण्न स्यादेतयोरर्थयोः।

कष्टं दुःखं तत्कारणं च । 'स्यात्कष्टं कृच्छ्रमाभीलम्' । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ।

३०६३ । घुषिरविशब्दने । ७ । २ । २३ । घुषेर्निष्ठायामानिट् स्यात् । घुष्टा रज्जुः । घु 'अविशब्दने' किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ।

३०६४ । अर्देः संनिविभ्यः । ७ । २ । २४ । एतत्पूर्वादर्देर्निष्ठाया इण्न स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ।

३०६५ । अभेश्चाविदूर्ये । ७ । २ । २५ । अभ्यर्णम् । नातिदूरमासन्नं वा । अभ्यर्दितमन्यत् ।

३०६६ । णेरध्ययने वृत्तम् । ७ । २ । २६ । ण्यन्ताद्वृत्तेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दश्छात्रेण संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिता रज्जुः ।

३०६७ । शृतं पाके । ६ । १ । २७ । श्रातिश्रपयत्योः क्ते शृभावो निपात्यते क्षीरहविषोः पाके । शृतं क्षीरं स्वयमेव विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविर्भ्यामन्यत्तु श्राणं-श्रपितं वा ।

३०६८ । वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः । ७ । २ । २७ । एते णिचि निष्ठान्ता वा निपात्यन्ते । पक्षे । दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञपितः ।

३०६९ । रुष्यमत्वरसंघुषास्वनाम् । ७ । २ । २८ । एभ्यो निष्ठाया इड्वा । रुषितः—रुष्टः । आन्तः—अमितः । तूर्णः—त्वरितः । अस्यादित्वे फलं मन्दम् । संघुष्टः—संघुषितः । आस्वान्तः—आस्वनितः ।

३०७० । हृषेर्लोमसु । ७ । २ । २९ । हृषेर्निष्ठाया इड्वा स्यात् लोमसु विषये । हृष्टं—हृषितं लोम । 'विस्मितप्रतिघातयोश्च' (वा ४४१७) । हृष्टो—हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । 'हृषु अलीके' उदित्त्वान्निष्ठायां नेट् । 'हृष तुष्टौ' इट् ।

३०७१ । अपचितश्च । ७ । २ । ३० । चायतेर्निपातोऽयं वा । अपचितः—अपचायितः ।

३०७२ । प्यायः पी । ६ । १ । २८ । पी वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं मुखम् । अन्यत्र प्यानः-पीनः स्वेदः । 'सोपसर्गस्य न' (वा ५०६५) प्रप्यानः । 'आङ्पूर्वस्यान्धूधसोः (स्यादेव)' (वा ३४६१) । आपीनोऽन्धुः । आपीनमूधः ।

३०७३ । ह्लादो निष्ठायाम् । ६ । ४ । ९५ । ह्रस्वः स्यात् । प्रह्लन्नः ।

३०७४ । द्यतिस्यतिमास्थामित्ति किति । ७ । ४ । ४० । एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्त्वदत्त्वयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ।

३०७५ । शाच्छोरन्यतरस्याम् । ७ । ४ । ४१ । शितः—शातः । छितः—छातः । व्यवस्थितविभाषात्वाद्व्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ।

३०७६ । दधातेर्हिः । ७ । ४ । ४२ । तादौ किति । अभिहितम् । निहितम् ।

३०७७ । दो दद्घोः । ७ । ४ । ४६ । घुसंज्ञकस्य 'दा' इत्यस्य 'दद्' स्यात्तादौ किति-

---

१ इदं च 'आङ्पूर्वस्यान्धूधसोः' (वा ३४६१) इति वार्तिकस्य 'अङ्पूर्वस्यैव' इति नियमसिद्धम् ।

चर्त्वम्। दत्तः। 'घोः' किम्। दातः। तान्तो वायमादेशः। न चैवं विदत्तमित्यादावुपसर्गस्य 'दास्ति' (सू २०७९) इति दीर्घापत्तिः। तकारादौ तद्विधानात्। दान्तो वा। धान्तो वा। न च दान्तत्वे निष्ठानत्वं धान्तत्वे 'झषस्तथोः-' (सू २२८०) इति धत्वं शङ्क्यम्। संनिपातपरिभाषाविरोधात्।

३०७८। अच उपसर्गात्तः। ७। ४। ४७। अजन्तादुपसर्गात्परस्य 'दा' इत्यस्य घोरचस्तः स्यात्तादौ किति। चर्त्वम्। प्रत्तः। अवत्तः।

"अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते॥" [इति भाष्यम्]

चशब्दाद्यथाप्राप्तम्।

३०७९। दस्ति। ६। ३। १२४। इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे। 'खरि च' (सू १२१) इति चर्त्वमाश्रयात्सिद्धम्। नीत्तम्। सूत्तम्। नी 'घुमास्था-' (सू २४६२) इतीत्वम्। धेट्। धीतम्। गीतम्। पीतम्। 'जनसन-' (सू २५०४) इत्यात्वम्। जातम्। सातम्। खातम्।

३०८०। अदो जग्धिर्ल्यप्ति किति। २। ४। ३६। ल्यबिति लुप्तसप्तमीकम्। अदो जग्धिः स्याल्ल्यपि तादौ किति च। इकार उच्चारणार्थः। धत्वम्। 'झरो झरि-' (सू ७१) जग्धः। 'आदिकर्मणि क्तः कर्तरि च' (सू ३०९३)। प्रकृतः कटं सः। प्रकृतः कटस्तेन 'निष्ठायामण्यदर्थे' (सू ३०१४) इति दीर्घः। 'क्षियो दीर्घात्' (सू ३०१५) इति नत्वम्। प्रक्षीणः सः।

३०८१। वाक्रोशदैन्ययोः। ६। ४। ६१। क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च। क्षीणायुर्भव। क्षितायुर्वा। क्षीणोऽयं तपस्वी। क्षितो वा।

३०८२। निनदीभ्यां स्नातेः कौशले। ८। ३। ८९। आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये। निष्णातः शास्त्रेषु। नद्यां स्नातीति नदीष्णः। 'सुपि-' (सू २९१६) इति कः।

३०८३। सूत्रं प्रतिष्णातम्। ८। ३। ९०। प्रतेः स्नातेः षत्वम्। प्रतिष्णातं सूत्रम्। शुद्धमित्यर्थः। अन्यत्र प्रतिस्नातम्।

३०८४। कपिष्ठलो गोत्रे। ८। ३। ९१। कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः 'गोत्रे' किम्। कपीनां स्थलं कपिस्थलम्।

३०८५। विकुशमिपरिभ्यः स्थलम्। ८। ३। ९६। एभ्यः स्थलस्य सस्य षः स्यात्। विष्ठलम्। कुष्ठलम्। शमिष्ठलम्। परिष्ठलम्।

३०८६। गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च। ३। ४। ७२। एभ्यः कर्तरि क्तः स्याद्भावकर्मणोश्च। गङ्गां गतः। गङ्गां प्राप्तः। म्लानः सः। लक्ष्मीमाश्लिष्टो हरिः। शेषमधिशयितः। वैकुण्ठमधिष्ठितः। शिवमुपासितः। हरिदिनमुपोषितः। राममनुजातः। गरुडमारूढः। विश्वमनुजीर्णः। पक्षे प्राप्ता गङ्गा तेनेत्यादि।

३०८७। क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः। ३। ४। ७६। एभ्योऽधिकरणे क्तः स्यात्। चाद्यथाप्राप्तम्। ध्रौव्यं स्थैर्यम्।

मुकुन्दस्यासितमिदमिदं यातं रमापतेः।
भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः॥

पक्ष आसेरकर्मकत्वात्कर्तरि भावे च। आसितो मुकुन्दः। आसितं तेन। गत्यर्थेभ्यः कर्तरि कर्मणि च। रमापतिरिदं यातः। तेनेदं यातम्। भुजेः कर्मणि। अनन्तेनेदं भुक्तम्। कथम् 'भुक्ताब्राह्मणाः' इति। भुक्तमस्ति एषामिति मत्वर्थीयोऽच्। वर्तमान इत्यधिकृत्य।

३०८८। ञीतः क्तः। ३। २। १८७। ञिक्ष्विदा। क्ष्विण्णः। ञीइन्धी। इद्धः।

३०८९। मतिबुद्धिपूजार्थेभ्यश्च। ३। २। १८८। मतिरिहेच्छा बुद्धेः पृथगुपादानात्। राज्ञां मत इष्टः। तैरिष्यमाण इत्यर्थः। बुद्धः। विदितः। पूजितः। अर्चितः। चकारोऽनुक्तसमुच्चयार्थः। शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि।

३०९०। नपुंसके भावे क्तः। ३। ३। ११४। क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः स्यात्। जल्पितम्। शयितम्। हसितम्।

३०९१। सुयजोर्ङ्वनिप्। ३। २। १०३। सुनोतेर्यजेश्च ङ्वनिप्स्याद्भूते। सुत्वा। सुत्वानौ। यज्वा। यज्वानौ।

३०९२। जीर्यतेरतृन्। ३। २। १०४। भूत इत्येव। जरन्। जरन्तौ। जरन्तः। वासरूपन्यायेन निष्ठापि। जीर्णो जीर्णवान्।

३०९३। छन्दसि लिट्। ३। २। १०५।

३०९४। लिटः कानज्वा। ३। २। १०६।

३०९५। क्वसुश्च। ३। २। १०७। इह भूतसामान्ये छन्दसि लिट्। तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम्। कवयस्तु बहुलं प्रयुञ्जते। 'तं तस्थिवांसं नगरोपकण्ठे'। 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि।

३०९६। वस्वेकाजाद्घसाम्। ७। २। ६७। कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम्। एकाच्। आरिवान्। आत्। ददिवान्। जक्षिवान्। 'एषाम्' किम्। बभूवान्।

३०९७। भाषायां सदवसश्रुवः। ३। २। १०८। सदादिभ्यो भूतसामान्ये भाषायां लिड्वा स्यात् तस्य च नित्यं क्वसुः। 'निषेदुषीमासनबन्धधीरः'। 'अध्यूषुषस्तामभवज्जनस्य'। शुश्रुवान्।

३०९८। उपेयिवाननाश्वाननूचानश्च। ३। २। १०९। एते निपात्यन्ते। उपपूर्वादिणो भाषायामपि भूतमात्रे लिड्वा तस्य नित्यं क्वसुः। इट्। उपेयिवान्। 'उपेयुषः स्वामपि मूर्तिमग्र्याम्'। उपेयुषी। उपेत्यविवक्षितम्। ईयिवान्। समीयिवान्। नञ्पूर्वादश्नातेः क्वसुरिडभावश्च। 'धृतजयधृतेरनाशुषः' इति भारविः। अनुपूर्वाद्वचेः कर्तरि कानच्। वेदस्यानुवचनं कृतवाननूचानः।

३०९९। विभाषा गमहनविदविशाम्। ७। २। ६८। एभ्यो वसोरिड्वा। जग्मिवान्-जगन्वान्। जघ्निवान्-जघन्वान्। विविदिवान्-विविद्वान्। विविशिवान्-विविश्वान्। विशिना

साहचर्याद्विन्दतेर्ग्रहणम्। वेत्तेस्तु विविद्वान्। 'नेड्वशि कृति' (सू २९८१) इतीण्निषेधः। 'दृशेश्च' (वा ४४५२)। ददृशिवान्। ददृश्वान्।

३१००। लटः शतृशानचावप्रथमासमानाधिकरणे। ३। २। १२४। अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः। शबादि। पचन्तं चैत्रं पश्य।

३१०१। आने मुक्। ७। २। ८२। अङ्गस्यातो मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम्। तेन प्रथमासामानाधिकरण्येऽपि क्वचित्। सन्ब्राह्मणः। 'माङ्याक्रोश इति वाच्यम्' (वा २१०९)। 'मा जीवन्यः परावज्ञा-दुःखदग्धोऽपि जीवति'। 'माङि लुङ्' (सू २२१९) इति प्राप्ते। एतद्वचनसामर्थ्याल्लट्।

३१०२। संबोधने च। ३। २। १२५। हे पचन्। हे पचमान।

३१०३। लक्षणहेत्वोः क्रियायाः। ३। २। १२६। क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः। शयाना भुञ्जते यवनाः। अर्जयन्वसति। हरिं पश्य-न्मुच्यते। हेतुः फलं कारणं च। 'कृत्यचः' (सू २८३५)। प्रपीयमाणः सोमः।

३१०४। ईदासः। ७। २। ८३। आसः परस्यानस्येत्स्यात्। 'आदेः परस्य' (सू४४) आसीनः।

३१०५। विदेः शतुर्वसुः। ७। १। ३६। वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात्। विदन्। विद्वान्। विदुषी।

३१०६। तौ सत्। ३। २। १२७। तौ शतृशानचौ सत्संज्ञौ स्तः।

३१०७। लृटः सद्वा। ३। ३। १४। व्यवस्थितविभाषेयम्। तेनाप्रथमासामा-नाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम्। करिष्यन्तं करिष्यमाणं पश्य। करिष्यतोऽपत्यं कारिष्यतः। करिष्यद्भक्तिः। हे करिष्यन्। अर्जयिष्यन्वसति। प्रथमासमानाधिकरणेऽपि क्वचित्। करिष्यतीति करिष्यन्।

३१०८। पुङ्यजोः शानन्। ३। २। १२८। वर्तमाने। पवमानः। यजमानः।

३१०९। ताच्छील्यवयोवचनशक्तिषु चानश्। ३। २। १२९। एषु द्योत्येषु कर्तरि चानश्। भोगं भुञ्जानः। कवचं बिभ्राणः। शत्रुं निघ्नानः।

३११०। इङ्धार्योः शत्रकृच्छ्रिणि। ३। २। १३०। आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि। अधीयन्। धारयन्। 'अकृच्छ्रिणि' किम्। कृच्छ्रेणाधीते। धारयति।

३१११। द्विषोऽमित्रे। ३। २। १३१। द्विषञ्छत्रुः।

३११२। सुञो यज्ञसंयोगे। ३। २। १३२। सर्वे सुन्वन्तः, सर्वे यजमानाः। सत्त्रिणः।

३११३। अर्हः प्रशंसायाम्। ३। २। १३३। अर्हन्।

३११४। आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु। ३। २। १३४। क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः।

३११५। तृन्। ३। २। १३५। कर्ता कटम्।

३११६। अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचरइष्णुच्। ३। २। १३६। अलंकरिष्णुः। निराकरिष्णुः। प्रजनिष्णुः। उत्पचिष्णुः। उत्पतिष्णुः। उन्मदिष्णुः। रोचिष्णुः। अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः। चरिष्णुः।

३११७। नेड्वशि कृति। ३।२।१३७। 'वीरुधः पारयिष्णवः'।

३११८। भुवश्च। ३।२।१३८। छन्दसीत्येव। भविष्णुः। कथं तर्हि 'जगत्प्रभोरप्रभ-विष्णु वैष्णवम्' इति। निरंकुशाः कवयः। चकारोऽनुक्तसमुच्चयार्थः। भ्राजिष्णुरिति वृत्तिः। एवं क्षयिष्णुः। नैतद्भाष्ये दृष्टम्।

३११९। ग्लाजिस्थश्च क्स्नुः। ३।२।१३९। छन्दसीति निवृत्तम्। गिदयं न तु कित्। तेन स्थ ईत्वं न। ग्लास्नुः। गित्त्वान्न गुणः। जिष्णुः। स्थास्नुः। चाद्भुवः। 'श्र्युकः किति' (सू २३८९) इत्यत्र गकारप्रश्लेषान्नेट्। भूष्णुः। 'दंशेश्छन्दस्युपसंख्यानम्' (वा २१३९)। दङ्क्ष्णवः पशवः।

३१२०। त्रसिगृधिधृषिक्षिपेः क्नुः। ३।२।१४०। त्रस्नुः। गृध्नुः। धृष्णुः। क्षिप्नुः।

३१२१। शमित्यष्टाभ्यो घिनुण्। ३।२।१४१। उकार उच्चारणार्थ इति काशिका। अनुबन्ध इति भाष्यम्। तेन शमिनितरा शमिनीतरेत्यत्र 'उगितश्च' (सू ९८७) इति ह्रस्वविकल्पः। न चैवं शमी शमिनावित्यादौ नुम्प्रसङ्गः। झल्ग्रहणमपकृष्य झलन्तानामेव तद्विधानात्। 'नोदात्तोपदेशस्य–' (सू २७६३) इति वृद्धिनिषेधः। शमी। तमी। दमी। श्रमी। भ्रमी। क्षमी। क्लमी। प्रमादी। उत्पूर्वान्मदेः अलंकृञादिसूत्रे-णेष्णुजुक्तो वासरूपविधिना घिनुणपि। उन्मादी। 'ताच्छीलिकेषु वासरूपविधिर्नास्ति' इति तु प्रायिकम्।

३१२२। संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटप-रिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषा-भ्याहनश्च। ३।२।१४२। घिनुण्स्यात्। संपर्की। अनुरोधी। आयामी। आयासी। परिसारी। संसर्गी। परिदेवी। संज्वारी। परिक्षेपी। परिराटी। परिवादी। परिदाही। परि-मोही। दोषी। द्वेषी। द्रोही। दोही। योगी। आक्रीडी। विवेकी। त्यागी। रागी। भागी। अतिचारी। अपचारी। आमोषी। अभ्याघाती।

३१२३। वौ कषलसकत्थस्रम्भः। ३।२।१४३। विकाषी। विलासी। विकत्थी। विस्रम्भी।

३१२४। अपे च लषः। ३।२।१४४। चाद्वौ। अपलाषी। विलाषी।

३१२५। प्रे लपसृद्रुमथवदवसः। ३।२।१४५। प्रलापी। प्रसारी। प्रद्रावी। प्रमाथी। प्रवादी। प्रवासी।

३१२६। निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्। ३।२।१४६। पञ्चम्यर्थे प्रथमा। एभ्यो वुञ्स्यात्। निन्दकः। हिंसक इत्यादि। ण्वुला सिद्धे वुञ्वचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजादयो नेति।

३१२७। देविक्रुशोश्चोपसर्गे। ३।२।१४७। आदेवकः। आक्रोशकः। 'उपसर्गे' किम्। देवयिता। क्रोष्टा।

३१२८। चलनशब्दार्थादकर्मकाद्युच्। ३।२।१४८। चलनार्थाच्छब्दार्थाच्च युच् स्यात्। चलनः। चोपनः। कम्पनः। शब्दनः। रवणः। 'अकर्मकात्' किम्। पठिता विद्याम्।

३१२९ । अनुदात्तेतश्च हलादेः । ३ । २ । १४९ । अकर्मकाद्युच्स्यात् । वर्तनः । वर्धनः । 'अनुदात्तेतः' किम् । भविता । 'हलादेः' किम् । एधिता । 'अकर्मकात्' किम् । वसिता वस्त्रम् ।

३१३० । जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः । ३ । २ । १५० । 'जु' इति सौत्रो धातुर्गतौ वेगे च । जवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदग्रहणं 'लषपतपद–' (सू ३१३४) इत्युकञा बाधा मा भूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ।

३१३१ । क्रुधमण्डार्थेभ्यश्च । ३ । २ । १५१ । क्रोधनः । रोषणः । मण्डनः । भूषणः ।

३१३२ । न यः । ३ । २ । १५२ । यकारान्ताद्युज्न स्यात् । क्नूयिता । क्ष्मायिता ।

३१३३ । सूददीपदीक्षश्च । ३ । २ । १५३ । युज्न स्यात् । सूदिता । दीपिता । दीक्षिता । 'नमिकम्पि–' (सू ३१४७) इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति 'ताच्छीलिकेषु वासरूपविधिर्नास्ति' (उ) इति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज्न कथं मधुसूदनः । नन्द्यादिः ।

३१३४ । लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् । ३ । २ । १५४ । लाषुकः । पातुक इत्यादि ।

३१३५ । जल्पभिक्षकुट्टलुण्टवृङः षाकन् । ३ । २ । १५५ । जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ।

३१३६ । प्रजोरिनिः । ३ । २ । १५६ । प्रजवी । प्रजविनौ । प्रजविनः ।

३१३७ । जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च । ३ । २ । १५७ । जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ।

३१३८ । स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् । ३ । २ । १५८ । आयाम्ब-यश्चुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः । 'शीङो वाच्यः' (वा २१४०) । शयालुः ।

३१३९ । दाधेट्सिशदसदो रुः । ३ । २ । १५९ । दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ।

३१४० । सृघस्यदः क्मरच् । ३ । २ । १६० । सृमरः । घस्मरः । अद्मरः ।

३१४१ । भञ्जभासमिदो घुरच् । ३ । २ । १६१ । भङ्गुरः । भासुरः । मेदुरः ।

३१४२ । विदिभिदिच्छिदेः कुरच् । ३ । २ । १६२ । विदुरः । भिदुरम् । छिदुरम् ।

३१४३ । इण्नशजिसर्तिभ्यः क्वरप् । ३ । २ । १६३ । इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ।

३१४४ । गत्वरश्च । ३ । २ । १६४ । गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ।

३१४५ । जागरूकः । ३ । २ । १६५ । जागर्तेरूकः स्यात् । जागरूकः ।

३१४६ । यजजपदशां यङः । ३ । २ । १६६ । एभ्यो यङन्तेभ्य ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जंजपूकः । दंदशूकः ।

३१४७ । नमिकम्पिस्म्यजसकमहिंसदीपो रः । ३ । २ । १६७ । नम्रः । कम्प्रः । स्मेरः । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रं संततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ।

३१४८ । सनाशंसभिक्ष उः । ३ । २ । १६८ । चिकीर्षुः । आशंसुः । भिक्षुः ।

३१४९ । विन्दुरिच्छुः । ३ । २ । १६९ । वेत्तेर्नुमिषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दुः । इच्छति इच्छुः ।

३१५० । क्याच्छन्दसि । ३ । २ । १७० । 'देवाञ्जिगाति सुम्नयुः' ।

३१५१ । आदृगमहनजनः किकिनौ लिट् च । ३ । २ । १७१ । आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्वत् । पपिः सोमम् । ददिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । 'जघ्निर्वृत्रममित्रियम्' जज्ञिः । 'भाषायां धाञ्कृसृगमिजनिनमिभ्यः' (वा २१४४) दधिः । चक्रिः । सस्रिः । जग्मिः । जज्ञिः । नेमिः । 'सासहिवावहिचाचलिपापतीनामुपसंख्यानम्' (वा २१४४) । यङन्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते ।

३१५२ । स्वपितृषोर्नजिङ् । ३ । २ । १७२ । स्वप्नक् । तृष्णक् । तृष्णजौ । तृष्णजः । 'धृषेश्च' इति वाच्यमिति काशिकादौ । धृष्णक् ।

३१५३ । शृवन्द्योरारुः । ३ । २ । १७३ । शरारुः । वन्दारुः ।

३१५४ । भियः क्रुक्लुकनौ । ३ । २ । १७४ । भीरुः । भीलुकः । 'क्रुकन्नपि वाच्यः' (वा २१४५) । भीरुकः ।

३१५५ । स्थेशभासपिसकसो वरच् । ३ । २ । १७५ । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ।

३१५६ । यश्च यङः । ३ । २ । १७६ । यातेर्यङन्ताद्वरच्स्यात् । 'अतो लोपः' (सू२३८०) तस्य 'अचः परस्मिन्–' (सू५०) इति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । तस्य यलोपं प्रति स्थानिवद्भावनिषेधात् 'लोपो व्योः–' (सू ८७३) इति यलोपः । अल्लोपस्य स्थानिवत्त्वमाश्रित्यातो लोपे प्राप्ते 'वरे लुप्तं न स्थानिवत्' । यायावरः ।

३१५७ । भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् । ३ । २ । १७७ । विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । ऊर्क् । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः क्विप् । ग्रावस्तुत् ।

३१५८ । अन्येभ्योऽपि दृश्यते । ३ । २ । १७८ । क्विप् । छित् । भित् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घः क्वचिदसंप्रसारणं क्वचिद्द्वे क्वचिद्ध्रस्वः । तथा च वार्तिकम् । 'क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च' (वा २१४७–४८) । क्विब्वचीत्यादिनोणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौति आयतस्तूः । कटं प्रवते कटप्रूः । जुरुक्तः । श्रयति हरिं श्रीः । 'द्युतिगमिजुहोतीनां द्वे च' (वा २१४९) । दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् । 'जुहोतेर्दीर्घश्च' (वा २१४९) । जुहूः । 'दॄ भये' । अस्य ह्रस्वश्च । दीर्यति । ददृत् । 'ध्यायतेः संप्रसारणं च' (वा २१५१) । धीः ।

३१५९ । भुवः संज्ञान्तरयोः । ३ । २ । १७९ । मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ।

३१६० । विप्रसंभ्यो ड्वसंज्ञायाम् । ३ । २ । १८० । एभ्यो भुवो डुः स्यान्न तु संज्ञा-

याम्। विभुर्व्यापकः। प्रभुः स्वामी। संभुर्जनिता। संज्ञायां तु विभुर्नाम कश्चित्। 'मितद्र्वादिभ्य उपसंख्यानम्' (वा २१९२)। मितं द्रवतीति मितद्रुः। शतद्रुः। शम्भुः। अन्तर्भावितण्यर्थोऽत्र भवति।

३१६१। धः कर्मणि ष्ट्रन्। ३। २। १८१। धेटो धाञश्च कर्मण्यर्थे ष्ट्रन्स्यात्। 'धात्री जनन्यामलकीवसुमत्युपमातृषु'।

३१६२। दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे। ३। २। १८२। दाबादेः ष्ट्रन्स्यात्करणेऽर्थे। दायन्त्यनेन दात्रम्। नेत्रम्।

३१६३। तितुत्रतथसिसुसरकसेषु च। ७। २। ९। एषां दशानां कृत्प्रत्ययानामिण्न स्यात्। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। नद्ध्री।

३१६४। हलसूकरयोः पुवः। ३। २। १८३। पूङ्पूञोः करणे ष्ट्रन्स्यात्। तच्चेत्करणं हलसूकरयोरवयवः। हलस्य सूकरस्य वा पोत्रम्। मुखमित्यर्थः।

३१६५। अर्तिलूधूसूखनसहचर इत्रः। ३। २। १८४। अरित्रम्। लवित्रम्। धवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्।

३१६६। पुवः संज्ञायाम्। ३। २। १८५। पवित्रम्। येनाऽऽज्यमुत्पूयते, यच्चानामिकावेष्टनम्।

३१६७। कर्तरि चर्षिदेवतयोः। ३। २। १८६। पुव इत्रः स्यात् ऋषौ करणे, देवतायां कर्तरि। ऋषिर्वेदमन्त्रः। तदुक्तमृषिणेति दर्शनात्। पूयतेऽनेनेति पवित्रम्। देवतायां तु 'अग्निः पवित्रं स मा पुनातु'।

अथोणादयः।

१ 'कृवापाजिमिस्वदिसाध्यशूभ्य उण्'। करोतीति कारुः शिल्पी कारकश्च। 'आतो युक्-' (सू २७६१)। वातीति वायुः। पायुर्गुदम्। जयत्यभिभवति रोगाञ्जायुरौषधम्। मिनोति प्रक्षिपति देह ऊष्माणमिति मायुः पित्तम्। स्वादुः। साध्नोति परकार्यं साधुः। अश्नुत आशुः। शीघ्रम्। 'आशुर्व्रीहिः पाटलः स्यात्'। २ 'छन्दसीणः'। 'मा न आयौ'। ३ 'दृसनिजनिचरिचटिभ्यो ञुण्'। दीर्यत इति दारु। 'स्नुः प्रस्थः सानुरस्त्रियाम्'। जानु। जानुनी। इह 'जनिवध्योश्च' (सू २५१२) इति न निषेधः। अनुबन्धद्वयसामर्थ्यात्। चारु रम्यम्। चाटु प्रियं वाक्यम्। मृगय्वादित्वात्कुप्रत्यये 'चटु' इत्यपि। ४ 'किंजरयोः श्रिणः'। किं शृणोतीति किंशारुः सस्यशूकं बाणश्च। जरामेति जरायुर्गर्भाशयः। 'गर्भाशयो जरायुः स्यात्'। ५ 'त्रो रश्च लः'। तरन्त्यनेन वर्णा इति तालुः। ६ 'कृके वचः कश्च'। कृकेन गलेन वक्तीति कृकवाकुः। 'कृकवाकुर्मयूरे च सरटे चरणायुधे' इति विश्वः। ७ 'भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः'। भरति बिभर्ति वा भरुः स्वामी हरश्च। म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः। शेते शयुरजगरः। तरुर्वृक्षः। चरन्ति भक्षयन्ति देवता इममिति चरुः। त्सरुः खड्गादिमुष्टिः। तनुः स्वल्पम्। तन्यते कर्मपाशोऽनया तनुः शरीरम् 'स्त्रियां मूर्तिस्तनुस्तनूः'। धनुः शस्त्रविशेषः। 'धनुर्ना च धनुर्विदुः'। 'धनुरिवाजनि वक्रः' इति श्रीहर्षः। मयुः किंनरः। 'मद्गुः ।नीयकाकिका' इति रभसः। न्यङ्क्वादित्वात्कुत्वं जश्त्वेन सस्य दः।

८ 'अणश्च' । 'लवलेशकणाणवः' । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटति वदतीति वटुः । ९ 'धान्ये नित्' । धान्ये वाच्येऽण उप्रत्ययः स्यात् । स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्ग्वश्वमेऽणवश्चमे । 'व्रीहिभेदस्त्वणुः पुमान्' । निद्ग्रहणं 'फलिपाटी–' इत्यादि सूत्रमभिव्याप्य संबध्यते । १० 'शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' । शृणातीति शरुः । 'शरुरायुधकोपयोः' । स्वरुर्वज्रम् । स्नेहुर्व्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । 'पुंसि भूम्न्यसवः प्राणाः' । 'वसुर्मयूखाग्निधनाधिपेषु' ... 'वसुर्देवेऽग्नौ योक्त्रेऽशौ वसु तोये धने मणौ' । हनुर्वक्त्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः । चात् 'बिदि अवयवे' । बिन्दुः । ११ 'स्यन्देः संप्रसारणं धश्च' । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । १२ 'उन्देरिच्चादेः' । उनत्ति इन्दुः । १३ 'ईषेः किच्च' । ईषेरुः स्यात्स च किदादेरिकारादेशश्च । ईषते हिनस्ति इषुः शरः । 'इषुर्द्वयोः' १४ 'स्कन्देः सलोपश्च' । कन्दुः । १५ 'सृजेरसुम्च' । चात्सलोप उप्रत्ययश्च । रज्जुः । १६ 'कृतेराद्यन्तविपर्ययश्च' । ककारतकारयोर्विनिमयः । तर्कुः सूत्रवेष्टनम् । १७ 'नावञ्चेः' । न्यङ्क्वादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुर्मृगः । १८ 'फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च' । फलेर्गुक् फल्गुः । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यत इति मधु । जायत इति जतु । १९ 'वलेर्गुक्च' । 'वल संवरणे' । वल्गुः । २० 'शः कित्सन्वच्च' । श्यतेरुः स्यात्स च कित्सन्वच्च । शिशुर्बालः । २१ 'यो द्वे च' ययुरश्वोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्त्वनिवृत्त्यर्थम् । २२ 'कुर्भ्रश्च' । 'बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ' । चादन्यतोऽपि । चक्रुः कर्ता जघ्नुर्हन्ता । पपुः पालकः । २३ 'पृभिदिव्यधिधृषिभ्यः' । कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । 'ग्रहिज्या–' (सू २४१२) इति संप्रसारणम् । विरहिणं विध्यति विधुः । 'विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे' । गृधुः कामः । धृषुर्दक्षः । २४ 'कृग्रोरुच्च' । करोतीति कुरुः । गृणातीति गुरुः । २५ 'अपदुःसुषु स्थः' । 'सुषामादिषु च' (सू १०२२) इति षत्वम् । अपष्ठु प्रतिकूलम् । दुष्ठु । सुष्ठु । २६ 'रपेरिच्चोपधायाः' । अनिष्टं रपतीति रिपुः । २७ 'अर्जिदृशिकम्यमिपंसिबाधामृजिपशितुग्धुग्दीर्घहकाराश्च' । अर्जयति गुणानृजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः कूपः । 'पांसुर्ना न द्वयो रजः' । 'तालव्या अपि दन्त्याश्च संबसूकरपांसवः' । बाधत इति 'बाहुः स्त्रीपुंसयोर्भुजः' । २८ 'प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च' । त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्क्वादित्वात्कुत्वम् । भृज्जाति तपसा भृगुः । २९ 'लङ्घिबंह्योर्नलोपश्च' । लघुः । 'बालमूललघ्वमङ्गुलीनां वा लो रत्वमापद्यते' (वा ४७९८) । रघुर्नृपभेदः । बहुः । ३० 'ऊर्णोतेर्नुलोपश्च' । ऊरु सक्थि । ३१ 'महति ह्रस्वश्च' । उरु महत् । ३२ 'श्लिषेः कश्च' । श्लिष्यतीति श्लिकुर्भृत्यः । उद्यतो ज्योतिश्च । ३३ 'आङ्परयोः खनिशृभ्यां डिच्च' । आ खनतीत्याखुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शुरपि । ३४ 'हरिमितयोर्द्रुवः' । 'द्रु गतौ' अस्माद्धरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्द्रूयते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः । ३५ 'शते च' । शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवतीत्यूर्ध्वमिति द्रुर्वृक्षः शाखा च । तद्वान्द्रुमः । ३६ 'खरुशङ्कु–पीयु–नीलङ्गु–लिगु' । पञ्चैते कुप्र-

त्ययान्ता निपात्यन्ते। खनते रेफश्चान्तादेशः। खरुः कामः। क्रूरो मूर्खोऽश्वश्च। 'शङ्कुर्ना कीलशल्ययोः'। 'पिबतेरीत्वं युगागमश्च'। पीयुर्वायसः कालः सुवर्णं च। निपूर्वाल्लगिगतावस्मात्कुर्नेर्दीर्घश्च। नीलङ्गुः कृमिविशेषः शृगालश्च। 'नीलाङ्गुः' इति पाठान्तरम्। तत्र धातोरपि दीर्घः। 'लग सङ्गे' अस्मात इत्वं च। लगतीति लिगु चित्तम्। लिगुर्मूर्खः। ३७ 'मृगय्वादयश्च'। एते कुप्रत्ययान्ता निपात्यन्ते। मृगं यातीति मृगयुर्व्याधः। देवयुर्धार्मिकः। मित्रयुर्लोकयात्राभिज्ञः। आकृतिगणोऽयम्। ३८ 'मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्'। मन्दुरा वाजिशाला। वाशुरा रात्रिः। मथुरा। चतुरः। चङ्कुरो रथः। अङ्कुरः। खर्जूरादित्वादङ्कूरोऽपि। ३९ 'व्यथेः संप्रसारणं किच्च'। 'विथुरश्चोरर-क्षसोः'। ४० 'मुकुरदर्दुरौ'। मुकुरो दर्पणः। बाहुलकान्मकुरोऽपि। 'दॄ विदारणे' धातोर्द्विर्वचनमभ्यासस्य रुक्टिलोपश्च। 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः'। 'दर्दुरा चण्डिकायां स्याद्ग्रामजाले च दर्दुरम्' इति विश्वः। ४१ 'मद्गुरादयश्च'। उरजन्ता निपात्यन्ते। माद्यतेर्गुक्। मद्गुरो मत्स्यभेदः। 'कर्बृ वर्णे'। रुगागमः। 'कर्बुरः श्वेतरक्षसोः'। बध्नातेः खर्जूरादित्वादूरोऽपि। 'बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु' इति रन्तिदेवः। 'कोकतेर्वा कुक् (च)' (गण. १९९)कुक्कुरः–कुकुरः। ४२ 'असेरुरन्'। असुरः। प्रज्ञाद्यण्। आसुरः। ४३ 'मसेश्च'। पञ्चमे पादे 'मसेरूरन्' इति वक्ष्यते। 'मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति'। 'मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः'। 'मसूरी पादरोगे स्यादुपधाने पुनः पुमान्'। 'मसूरमसुरौ च द्वौ' इति विश्वः। ४४ 'शावशेराप्तौ'। शु इत्याशुर्थे। श्वशुरः। 'पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः' इत्यमरः। ४५ 'अविमह्योष्टिषच्'। अविषः। महिषः। ४६ 'अमेर्दीर्घश्च'। 'आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि'। ४७ 'रुहेर्वृद्धिश्च'। 'रङ्कुशम्बररौहिषाः'। 'रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतम्' इति संसारावर्तः। ४८ 'तवेर्णिद्वा'। 'तव' इति सौत्रो धातुः। 'तविषताविषावब्धौ स्वर्गे च'। स्त्रियां तविषी–ताविषी नदी देवकन्या भूमिश्च। 'तविषी बलम्' इति वेदभाष्यम्। ४९ 'नञि व्यथेः'। 'अव्यथिषोऽब्धिसूर्ययोः'। अव्यथिषी धरारात्र्योः। ५० 'किलेर्बुक्च'। किल्बिषम्। ५१ 'इषिमदिमुदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्'। इषिरोऽग्निः। मदिरा सुरा। 'मुदिरः कामुकाभ्रयोः' इति विश्वमेदिन्यौ। खिदिरश्चन्द्रः। 'छिदिरोऽसिकुठारयोः'। भिदिरं वज्रम्। मन्दिरं गृहम्। स्त्रियामपि। 'मन्दिरं मन्दिरापि स्यात्' इति विश्वः। 'चन्दिरो चन्द्रहस्तिनौ'। तिमिरं तमोऽक्षिरोगश्च। मिहिरः सूर्यः। 'मुहिरः काम्यसभ्ययोः'। मुचिरो दाता। रुचिरम्। रुधिरम्। बधिरः। 'शुष शोषणे' शुषिरं छिद्रम्। शुष्कमित्यन्ये। ५२ 'अशेर्णित्'। आशिरो वह्निरक्षसोः। ५३ 'अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः'। अजेर्वीभावाभावः। अजिरमङ्गणम्। शशेरुपधाया इत्वम्। 'शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत्'। 'श्रथ मोचने' उपधाया इत्वं रेफलोपः। प्रत्ययरेफस्य लत्वम्। शिथिलम्। स्थास्फाय्योष्टिलोपः। स्थिरं निश्चलम्। स्फिरं प्रभूतम्। तिष्ठतेर्वुक्ह्रस्वत्वं च। स्थविरः। खादिरः। बाहुलकाच्छीङो वुक्ह्रस्वत्वं च। शिबिरम्। ५४ 'सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्'। सलति गच्छति निम्नमिति सलिलम्। कलिलम्। अनिलः। महिला। पृषोदरादित्वान्महे-

लापि। भड इति सौत्रो धातुः। 'भडिलौ शूरसेवकौ'। भण्डिलो दूतः कल्याणं च। शण्डिलो मुनिः। विण्डिलो गणकः। तुण्डिलो मुखरः। कोकिलः। भविलो भव्यः। बाहुलकात्कुटिलः। ९५ 'कमेः पश्च'। कपिलः। ९६ 'गुपादिभ्यः कित्'। गुपिलो राजा। तिजिलो निशाकरः। गुहिलं वनम्। ९७ 'मिथिलादयश्च'। मथ्यन्तेऽत्र रिपवो मिथिला नगरी पथिलः—पथिकः। ९८ 'पतिकठिकुठिगडिगुडिदंशिभ्य एरक्'। पतेरः पक्षी गन्ता च। कठेरः कृच्छ्रजीवी। कुठेरः पर्णाशः। बाहुलकान्नुम्। गडेरो मेघः। गुडेरो गुडकः। दंशेरो हिंस्रः। ९९ 'कुम्बेर्नलोपश्च'। कुबेरः। ६० 'शदेस्त च'। शतेरः शत्रुः। ६१ 'मूलेरादयः' एरगन्ता निपात्यन्ते। मूलेरो जटा। गुधेरो गोप्ता। गुहेरो लोहघातकः। मुहेरो मूर्खः। ६२ 'कबेरोतच्पश्च'। कपोतः पक्षी। ६३ 'भातेर्डवतुः'। भातीति भवान्। ६४ 'कठिचकिभ्यामोरन्'। कठोरः। चकोरः। ६५ 'किशोरादयश्च'। किंपूर्वस्य शृणातेष्टिलोपः। किमोऽन्त्यलोपः। किशोरोऽश्वशावः। सहोरः साधुः। ६६ 'कपिगडिगण्डिकटिपटिभ्य ओलच्'। कपीति निर्देशान्नलोपः। कपोलः। गडोलगण्डोलौ गुडकपर्यायौ। कटोलः कटुः। पटोलः। ६७ 'मीनातेरूरन्'। मयूरः। ६८ 'स्यन्देः संप्रसारणं च'। सिन्दूरम्। ६९ 'सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्'। सिनोतीति सेतुः। 'तितुत्र—' (सू ३१६३) इति नेट्। तन्तुः। गन्तुः। मस्तु दधिमण्डम्। सच्यत इति सक्तुः। अर्धर्चादिः। 'ज्वर त्वर—' (सू २६५४) इत्यूठ्। तत्र क्ङितीत्यनुवर्तत इति मते तु बाहुलकात्। ओतुर्बिडालः। धातु। क्रोष्टा। ७० 'पः किच'। पिबतीति 'पितुर्वह्नौ दिवाकरे'। ७१ 'अर्तेश्च तुः'। अर्तेस्तुः स्यात्स च कित् 'ऋतुः स्त्रीपुष्पकालयोः'। ७२ 'कमिमनिजनिगाभायाहिभ्यश्च'। एभ्यस्तुः स्यात्। 'कन्तुः कंदर्पचित्तयोः'। मन्तुरपराधः। जन्तुः प्राणी। 'गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च'। भातुरादित्यः। 'यातुरध्वगकालयोः'। रक्षसि क्लीबः। हेतुः कारणम्। ७३ 'चायः किः'। 'केतुर्ग्रहपताकयोः'। ७४ 'आप्नोतेर्ह्रस्वश्च'। अप्तुः शरीरम्। ७५'वसेस्तुन्'। वस्तु। ७६ 'अगारे णिच'। 'वेश्मभूर्वास्तुरस्त्रियाम्'। ७७ 'कृञः क्रतुः'। क्रतुर्यज्ञः। ७८ 'एधिवह्योश्चतुः'। एधतुः पुरुषः। वहतुरनड्वान्। ७९ 'जीवेरातुः': 'जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे'। ८० 'आतृकन्वृद्धिश्च'। जीवेरित्येव। 'जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृपीवले'। ८१ 'कषिचमितनिधनिसर्जिखर्जिभ्य ऊः'। 'कषूः पुंसि करीषाग्नौ कषूर्नद्यां स्त्रियां मता'। चमूः। तनूः। धनूः शस्त्रम्। 'सर्ज सर्जने'। सर्जूर्वणिक्। 'खर्ज व्यथने'। खर्जूः पामा। ८२ 'मृजेर्गुणश्च'। मर्जूः शुद्धिकृत्। ८३ 'वहो धश्च'। 'वधूर्जायास्नुषास्त्रीषु'। ८४ 'कषेश्छश्च'। कच्छूः पामा। ८५ 'णित्कसिपद्यर्तेः'। कासूः शक्तिः। पादूश्चरणधारिणी। आरूः पिङ्गलः। ८६ 'अणो डश्च'। आडूर्जलप्लवद्रव्यम्। ८७ 'नञि लम्बेर्नलोपश्च'। 'तुम्ब्यलाबूरुभे समे' इत्यमरः। ८८ 'के श्र एरङ् चास्य'। कशब्द उपपदे शृणातेरूः स्यादेरङादेशः। 'कशेरूस्तृणकन्दे स्त्री' बाहुलकादुप्रत्यये कशेरुः क्लीबे पुंसि च। ८९ 'त्रोदुट् च'। तरतेरूः स्यात्तस्य दुट्। 'तर्दूः स्याद्दारुहस्तकः'। ९० 'दरिद्रातेर्यालोपश्च'। इश्च आश्च यौ तयोर्लोपः। दर्द्रूः कुष्ठप्रभेदः। ९१ 'नृतिशृध्योः कूः'। नृतूर्नर्तकः। शृधूरपानम्। ९२ 'ऋतेरम्च'। ऋतिः सौत्रो धातुः। ततः कूरमागमश्च। रंतूर्देवनदी सत्यवाक्च। ९३ 'अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः'। एते कूप्रत्य-

यान्ता निपात्यन्ते। अन्दूर्बन्धनम्। 'दृभी ग्रन्थे' निपातनान्नुम्। दृम्भूः। अनुस्वाराभावोऽपि निपातनादित्येके। दृन्भूः। जनेर्बुक्। जम्बूः। 'जमु अदने' इत्यस्येत्येके - बाहुलकाद्ध्रस्वोऽपि। जम्बुः। कफं लाति कफेलूः श्लेष्मातकः। निपातनादेत्त्वम्। कर्कं दधाति कर्कन्धूर्बदरी। निपातनान्नुम्। दिधिं धैर्यं स्यति त्यजतीति दिधिषूः पुनर्भूः। केचित्तु 'अन्दूदृम्फूजम्बूकम्बू' इति पठन्ति। दृम्फ उत्क्लेशे' दृम्फूः सर्पजातिः। 'कमेर्बुक्'। कम्बूः परद्रव्यापहारी। ९४ 'मृग्रोरुतिः'। मरुत्। गरुत्पक्षः। ९५ 'ग्रो मुट् च'। गिरतेरुतिस्तस्य च मुट्। गर्मुत्सुवर्णं तृणविशेषश्च। ९६ 'हृषेरुलच्'। 'हर्षुलो मृगकामिनोः। बाहुलकाच्चटतेः। चटुलं शोभनम्। ९७ 'हृसृरुहियुषिभ्य इतिः'। 'हरित्ककुभि वर्णे च तृणवाजिविशेषयोः'। सरिन्नदी। 'रोहित्' मृगविशेषस्य स्त्री। 'युष' इति सौत्रो धातुः। मत्स्यस्य रोहित् पुरुषस्य योषिदिति भाष्यम्। ९८ 'ताडेर्णिलुक् च'। ताडयतीति तडित्। ९९ 'शमेर्ढः'। बाहुलकादित्संज्ञा यादेश इट् च न। 'शण्ढः स्यात्पुंसि गोपतौ'। शण्ढः क्लीबः। १०० 'कमेरठः'। कमठः। 'कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम्' इति मेदिनी। बाहुलकाज्जरठः। १०१ 'रमेर्वृद्धिश्च'। रामठं हिङ्गु। १०२ 'शमेः खः'। शङ्खः। १०३ 'कणेष्ठः'। कण्ठः। १०४ 'कलस्तृपश्च'। तृपतेः कलप्रत्ययः। चात्तृफतेः। तृपला लता। 'तृफला तु फलत्रिके'। १०५ 'शपेर्बश्च'। शबलः। १०६ 'वृषादिभ्यश्चित्'। वृषलः। पललम्। बाहुलकाद्गुणः। सरलः। तरलः। 'कमेर्बुक् (च)'(गण १९६) कम्बलः। 'मुस खण्डने' मुसलम्। 'लङ्गेर्वृद्धिश्च' (गण १९७) लाङ्गलम्। 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् (च)'(गण१९८) कुट्मलः। कुडेरपि। कुड्मलः। कश्मलम्। बाहुलकाद्गुणः। कोमलम्। १०७ 'मृजेष्टिलोपश्च'। मलम्। १०८ 'चुपेरच्चोपधायाः'। चपलम्। १०९ 'शकिशम्योर्नित्'। शकलम्। शमलम्। ११० 'छो गुग्घ्रस्वश्च'। छगलः। प्रज्ञादित्वाच्छागलः। १११ 'अमन्ताड्डः'। दण्डः। रण्डा। खण्डः। मण्डः। वण्डश्छिन्नहस्तः। अण्डः। बाहुलकात्सत्वाभावः। षण्डः संघातः। तालव्यादिरित्यपरे। शण्डः। गण्डः। चण्डः। पण्डः क्लीबः। पण्डा बुद्धिः। ११२ 'क्रादिभ्यः कित्'। कवर्गादिभ्यो डः कित्स्यात्। कुण्डम्। काण्डम्। गुड्। गुडः। 'घुण भ्रमणे' घुण्डो भ्रमरः। ११३ 'स्थाचतिमृजेरालज्वालञालीयचः'। तिष्ठतेरालच्। स्थालम्-स्थाली। चतेर्वालञ्। चात्वालः। मृजेरालीयच्। मार्जालीयो विडालः। ११४ 'पतिचण्डिभ्यामालञ्'। पातालम्। चण्डालः। प्रज्ञादित्वादणि चाण्डालोऽपीत्येके। ११५ 'तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्'। तमालः। विशालः। बिडालः। मृणालम्। कुलालः। कपालम्। पलालम्। पञ्चालाः। ११६ 'पतेरङ्गच्पक्षिणि'। पतङ्गः। ११७ 'तरत्यादिभ्यश्च'। तरङ्गः। लवङ्गम्। ११८ 'विडादिभ्यः कित्'। विडङ्गः। मृदङ्गः। कुरङ्गः। बाहुलकादुत्वं च। ११९ 'सृवृञोर्वृद्धिश्च'। सारङ्गः। वारङ्गः खड्गादिमुष्टिः। १२० 'गम्गम्ययोः'। मङ्गः अङ्गः पुरोडाशः। १२१ 'छापूखडिभ्यः कित्'। छागः। पूगः। खड्गः। बाहुलकात 'षिट अनादरे' गन्सत्वाभावश्च। षिड्गस्तरलः। 'षिड्गैरगायत ससंभ्रममेवमेका' इति माघः। १२२'भृञः किन्नुट् च'। भृञो गन्कित्स्याच्चस्य नुट् च। भृङ्गः, षिड्ग-

लिभूम्याटाः । १२३ 'शृणातेर्ह्रस्वश्च' । शृङ्गम् । १२४ 'गन्शकुनौ' । नुट् चेत्यनुवर्तते । शार्ङ्गः । १२५ 'मुदिग्रोर्गग्गौ' । मुद्गः । गर्गः । १२६ 'अण्डन्कृसृभृवृञः' करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः । १२७ 'शृदृभसोऽदिः' । शरत् । 'दरद्धृदयकूलयोः' । भसज्जघनम् । १२८ 'दृणातेः पुग्घ्रस्वश्च' । दृषत् । १२९ 'त्यजितनियजिभ्यो डित्' । त्यद् । तद् । यद् । सर्वादयः । १३० 'एतेस्तुट् च' । एतद् । १३१ 'सर्तेरटिः' । 'सरट् स्याद्वातमेघयोः' । वेदभाष्ये तु 'याभिः कृशानुम्' इति मन्त्रे 'सरड्भ्यो मधुमक्षिकाभ्यः' इति व्याख्यातम् । १३२ 'लङ्घेर्नलोपश्च' । लघट् वायुः । १३३ 'पारयतेरजिः' । पारक्सुवर्णम् । १३४ 'प्रथः कित्संप्रसारणं च' । पृथक् । स्वरादिपाठादव्ययत्वम् । १३५ 'भियः षुग्घ्रस्वश्च' । भिषक् । १३६ 'युष्यसिभ्यां मदिक्' । 'युष' सौत्रो धातुः युष्मद् । अस्मद् । त्वम् । अहम् । १३७ 'अर्तिस्तुसुहुसृधृक्षिक्षुभायावापदियक्षिनीभ्यो मन्' । एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षूरोगः । स्तोमः संघातः । सोमः । होमः । सर्मो गमनम् । धर्मः । क्षेमं कुशलम् । क्षोमम् । पट्टवस्त्राणि क्षौमं च । भाम आदित्यः । यामः । 'वामः शोभनदुष्टयोः' । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः । नेमः । १३८ 'जहातेः सन्वदालोपश्च' । 'जिह्मः कुटिलमन्दयोः' । १३९ 'अवतेष्टिलोपश्च' । मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । 'ज्वरत्वर–' (सू २६५४) इति ऊठ् । तयोर्दीर्घे कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । अवतीति ओम् । १४० 'ग्रसेरा च' । ग्रामः । १४१ 'अविसिविसिशुषिभ्यः कित्' । ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । 'शुष्ममग्निसमीरयोः' । १४२ 'इषियुधीन्धिदसिश्याधूसूभ्यो मक्' । 'इष्मः कामवसन्तयोः' । ईषीति पाठे दीर्घादिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यजमानः । श्यामः । धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीर्मं व्रणः । १४३ 'युजिरुचितिजां कुश्च' । युग्मम् । रुक्मम् । तिग्मम् । १४४ 'हन्तेर्हिं च' । हिमम् । १४५ 'भियः षुग्वा' । भीमः । भीष्मः । १४६ 'घर्मः' । घृधातोर्मग्गुणश्च निपात्यते । १४७ 'ग्रीष्मः' । ग्रसतेर्निपातोऽयम् । १४८ 'प्रथेः षिवन्संप्रसारणं च' । पृथिवी । षवन्नित्येके । पृथवी । 'पृथवी पृथिवी पृथ्वी' इति शब्दार्णवः । १४९ 'अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्' । अश्वः । 'प्रुष स्नेहनादौ' । 'प्रुष्वः स्यादृतुसूर्ययोः' । प्रुष्वा जलकणिका । लट्वा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्त्वे किण्वमपि । खट्वा । विश्वम् । १५० 'इण्शीभ्यां वन्' । एवो गन्ता । 'ये च एवा मरुतः' । असत्त्वे निपातोऽयम् । 'शेवं मित्राय वरुणाय' । १५१ 'सर्वनीघृष्वरिष्वलष्वशिवपद्वप्रह्वेष्वा अस्वतन्त्रे' । अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्घृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शंभुः । शीङो ह्रस्वत्वम् । पद्वो रथो भूलोकश्च । प्रह्वयत इति प्रह्वः । ह्वेञ आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । 'अस्वतन्त्रे' किम् । सर्ता सारकः । बाहुलकाद्ग्रसतेः । ह्रस्वः । १५२ 'शेवयह्वजिह्वाग्रीवाप्वमीवाः' । शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन यह्वः । ह्रस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः हुगाभावश्च । गिरन्त्यनया ग्रीवा । ईङागमश्च । आप्नोतीत्याप्वो वायुः । मीवा उदरकृमिः ।

वायुरित्यन्ये। १५३ 'कृगृशृदृभ्यो वः'। कर्वः काम आखुश्च। गर्वः। शर्वः। दर्वो राक्षसः। १५४ 'कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः'। यौतीति युवा। वृषेन्द्रः। तक्षा। राजा। धन्वा मरुः। धन्व शरासनम्। द्युवा सूर्यः। प्रतिदीव्यन्त्यस्मिन्प्रतिदिवा दिवसः। १५५ 'सप्यशूभ्यां तुट् च'। सप्त। अष्ट। १५६ 'नञि जहातेः'। अहः। १५७ 'श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्मन्मातरिश्वन्मघवन्निति'। एते त्रयोदश कनिन्प्रत्ययान्ता निपात्यन्ते। श्वयतीति श्वा। उक्षा। पूषा। 'प्लिह गतौ'। इकारस्य दीर्घत्वम्। प्लेहतीति प्लीहा कुक्षिव्याधिः। 'क्लिदू आर्द्रीभावे'। क्लिद्यति क्लेदा चन्द्रः। स्निह्यतेर्गुणः। स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च। मुह्यन्त्यस्मिन्नाहते मूर्धा। मुहेरुपधाया दीर्घो धोऽन्तादेशो रुमागमश्च। मज्जत्यस्थिषु मज्जा अस्थिसारः। अर्यपूर्वो माङ्। अर्यमा। विश्वं प्साति विश्वप्साग्निः। परिजायते परिज्मा चन्द्रोऽग्निश्च। जनेरुपधालोपो मश्चान्तादेशः। मातर्यन्तरिक्षे श्वयतीति मातरिश्वा। धातोरिकारलोपः। 'मह पूजायाम्'। हस्य घो वुगागमश्च। मघवेन्द्रः। इत्युणादिषु प्रथमः पादः।

१५८ 'कृहृभ्यामेणुः'। करेणुः। हरेणुर्गन्धद्रव्यम्। १५९ 'हनिकुषिनीरमिकाशिभ्यः क्थन्'। हथो विषण्णः। कुष्ठः। नीथो नेता। रथः काष्ठम्। १६० 'अवे भृञः'। अवभृथः। १६१ 'उषिकुषिगार्तिभ्यस्थन्'। ओष्ठः। कोष्ठम्। गाथा। अर्थः। बाहुलकाच्छोथः। १६२ 'सर्तेर्णित्'। सार्थः समूहः। १६३ 'जॄवृभ्यामूथन्'। जरूथं मांसम्। 'वरूथो रथगुप्तौ ना'। १६४ 'पातॄतुदिवचिरिचिसिचिभ्यस्थक्'। पीथो रविर्घृतं पीथम्। 'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु। अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतम्' इति विश्वः। तुत्थोऽग्निः। उक्थं सामभेदः। रिक्थम्। बाहुलकाद्रचेरपि। 'रिक्थमृक्थं धनं वसु'। सिक्थम्। १६५ 'अर्तेर्निरि'। निर्ऋथं साम। १६६ 'निशीथगोपीथावगथाः'। निशीथोऽर्धरात्रो रात्रिमात्रं च। गोपीथं तीर्थम्। अवगतः प्रातःस्नातः। १६७ 'गश्चोदि'। उद्गीथः साम्नो भागविशेषः। १६८ 'समीणः' समिथो वह्निः संग्रामश्च। १६९ 'तिथपृष्ठगूथयूथप्रोथाः'। तिजेर्जलोपः। तिथोऽनलः कामश्च। पृष्ठम्। गूथं विष्ठा। यूथं समूहः। 'प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते'। १७० 'स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्'। द्राघिशङ्क्यो रक्स्यात्। वलियलोपः। स्फारम्। न्यङ्क्वादित्वात्कुत्वम्। तक्रम्। वक्रम्। शक्रः। क्षिप्रम्। क्षुद्रः। सृप्रश्चन्द्रः। तृप्रः पुरोडाशः। दृप्रो बलवान्। वन्द्रः पूजकः। उन्दी। उन्द्रो जलचरः। श्वित्रं कुष्ठम्। 'वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे' अजेर्वी। वीरः। नीरम्। पद्रो ग्रामः। मद्रो हर्षो देशभेदश्च। 'मुद्रा प्रत्ययकारिणी'। 'खिद्रो रोगो दरिद्रश्च'। छिद्रम्। भिद्रं वज्रम्। मन्द्रः। चन्द्रः। पचाद्यचि चन्दोऽपि। 'हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः'। दह्रोऽग्निः। दस्रः स्वर्वैद्यः। 'दभ्रः समुद्रः स्वल्पं च'। वसेः संप्रसारणे।

३१६८। न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्। ८।३।११०। रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात्। 'पूर्वपदात्' (सू० ३६४३) इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया। तेन 'शासिवसि-' (सू० २४१०) इति प्राप्तमपि न। उस्रो रश्मिः। उस्रा गौः। वाश्रो दिवसः। वाश्रं मन्दिरम्। शीरोऽजगरः। हस्रो मूर्खः। सिध्रः साधुः। शुभ्रम्।

बाहुलकात् मुसेरक् । मुसलम् उदश्च । १७१ 'चक्रिरम्योरुच्चोपधायाः' । चुक्रमम्ल-द्रव्यम् । रुम्रोऽरुणः । १७२ 'वौ कसेः' । विकुसश्चन्द्रः । १७३ । 'अमितम्योर्दीर्घश्च' । आम्रम् । ताम्रम् । १७४ 'निन्देर्नलोपश्च' । निद्रा । १७५ 'अर्देर्दीर्घश्च' । आर्द्रम् । १७६ 'शुचेर्दश्च' । शूद्रः । १७७ 'दुरीणो लोपश्च' । दुःखेनेयते प्राप्यत इति दूरम् । १७८ कृतेच्छः क्रू च' । कृच्छ्रम् । क्रूरः । १७९ 'रोदेर्णिलुक् च' । रोदयतीति रुद्रः । १८० 'बहुलमन्यत्रापि संज्ञाछन्दसोः' । णिलुगित्येव । 'वान्तिपर्णशुषो वातास्ततः पर्णमुचोऽपरे' । १८१ 'जोरी च' । जीरोऽणुः । ज्यश्चेत्येके १८२ । 'सुसूधागृधिभ्यः क्रन्' । सुरः । सूरः । धीरः । गृध्रः । १८३ 'शुसिचिमीनां दीर्घश्च' । शुः सौत्रः शूरः । सीरम् । चीरम् । मीरः समुद्रः । १८४ 'वाविन्धेः' । वीध्रं विमलम् । १८५ 'वृधिवपिभ्यां रन्' । वर्ध्रं चर्म । वप्रः प्राकारः । १८६ 'ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवत्रेरामालाः' । रन्नन्ता ऊनविंशतिः निपातनाद्गुणाभावः । ऋज्रो नायकः । इदि, इन्द्रः । अङ्गेर्नलोपः । अग्रम् । 'वज्रोऽस्त्री हीरके पवौ' । डुवप्, उपधाया इत्त्वम् । विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुब्रं मुखम् । 'क्षुर विलेखने' रेफलोपः । अगुणः । क्षुरः । 'खुर छेदने' रलोपो गुणाभावश्च । खुरः । भन्देर्नलोपः । भद्रम् । 'उच समवाये' चस्य गः । उग्रः । ञिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्चस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् वृद्धिः । गौरोऽरुणे सिते पीते' 'वन संभक्तौ' । वत्रो विभागी । इणो गुणाभावः । 'इरा मद्ये च वारिणि' । 'मा मानेमाला' १८७ 'समि कस उकन्' । 'कस गतौ' । सम्यक्कसन्ति पलायन्ते जना अस्मादिति संकसुको दुर्जनः अस्थिरश्च । १८८ 'पचिनशोर्णुकन्कुनुमौ च' । पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः । १८९ 'भियः क्रुकन्' । भीरुकः । १९० 'क्रुन्शिल्पिसंज्ञयोरपूर्वस्यापि' । रजकः । इक्षुकुट्टकः । चरकः । 'चष भक्षणे' । चषकः । शुनकः । भषकः । १९१ । 'रमे रश्च लो वा' । रमको विलासी । लमकः । १९२ 'जहातेर्द्वे च' । जहकस्त्यागी कालश्च । १९३ 'ध्मो धम च' । धमकः कर्मकारः । १९४ 'हनो वध च' । वधकः । १९५ 'बहुलमन्यत्रापि' । 'कुह विस्मापने' । कुहकः । कृतकम् । १९६ 'कृषेर्वृद्धिश्चोदीचाम्' । कार्षकः—कृषकः । १९७ 'उदकं च' । प्रपञ्चार्थम् । १९८ 'वृश्चिकृषोः किकन्' । वृश्चिकः । कृषिकः । १९९ 'प्राङि पणिकषः' । प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी । 'मुषेर्दीर्घश्च' । २०० मूषिक आखुः । २०१ 'स्यमेः संप्रसारणं च' । चाद्दीर्घः सीमिको वृक्षभेदः । २०२ । 'क्रिय इकन्' । क्रयिकः क्रेता । २०३ 'आङि पणिपनिपतिखनिभ्यः' । आपणिकः । आपनिकः । इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च । २०४ 'श्यास्त्याहृञविभ्य इनच्' श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः । २०५ 'वृजेः किच्च' । वृजिनम् । २०६ 'अजेरज च' । वीभावबाधनार्थम् । अजिनम् । २०७ 'बहुलमन्यत्रापि' । कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः 'यत्परुषि दिनम्' दिवसोऽपि दिनम् । २०८ 'द्रुदक्षिभाग्यामिनन्' । द्रविणम् । दक्षिणः । दक्षिणा । २०९ 'अर्तेः किदिच्च' । इरिणं शून्यम् । २१० 'वेपितुह्योर्ह्रस्वश्च' । विपिनम् । तुहिनम् । २११ 'तलिपुलिभ्यां च' । 'तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु' । पुलिनम् । 'गर्वेरत उच्च' २१२ गौरादित्वान्ङीष् । गुर्विणी गर्भिणी । २१३ 'रुहेश्च' । रोहिणः । २१४ महेरिनण्च' । चादिनन् ।

माहिनम् । महिनं राज्यम् । २१५ 'क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च' । वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति स्रूर्यज्ञोपकरणम् । द्रूर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । 'जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम्' । २१६ 'आप्नोतेर्ह्रस्वश्च' । आपः । अपः । अद्भिः । अद्भ्यः । २१७ 'परौ व्रजेः षः पदान्ते' । व्रजेः क्विब्दीर्घौ स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ । २१८ 'हुवः श्लुवच्च' । जुहूः । २१९ 'स्रुवः कः' । स्रुवः । २२० 'चिक्च' । इकार उच्चारणार्थः । क इत् । कुत्वम् । स्रुक् । 'स्रुवं च स्रुचश्च संमृड्ढि' । २२१ 'तनोतेरनश्च वः' । तनोतेश्चिक्प्रत्ययः । अनो वशब्दादेशश्च । त्वक् । २२२ 'ग्लानुदिभ्यां डौः' । ग्लौः । नौः । २२३ 'च्विरव्ययम्' । डौरित्येव । ग्लौ करोति । 'कृन्मेजन्तः' (सू ४४९) इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्च्व्यन्त एवेति । २२४ 'रातेर्डैः' । राः । रायौ । रायः । २२५ 'गमेर्डोः' । 'गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु' । बाहुलकाद्द्युतेरपि डोः । 'द्यौः स्त्री स्वर्गान्तरिक्षयोः' । २२६ 'भ्रमेश्च डूः' । भ्रूः चाद्गमेः । अग्रेगूः । २२७ 'दमेर्डोसिः' । दोः । दोषौ । २२८ 'पणेरिज्यादेश्च वः' । वणिक् । स्वार्थेऽण् । 'नैगमो वाणिजो वणिक्' । २२९ 'वशेः कित्' । 'उशिगग्नौ घृतेऽपि च' । २३० 'भृञ ऊच्च' । भूरिक्भूमिः । २३१ 'जसिसहोरुरिन्' । जसुरिर्वज्रम् । सहुरिरादित्यः पृथिवी च । २३२ 'सुयुरुवृञो युच्' । सवनश्चन्द्रमाः । यवनः । रवणः । कोकिलः । वरणः । २३३ 'अशे रश च' । 'अश्नोतेर्युच्स्यात् रशादेशश्च' । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् । २३४ 'उन्देर्नलोपश्च' । ओदनः । २३५ 'गमेर्गश्च' । गमेर्युच्स्याद्गश्चादेशः । गगनम् । २३६ 'बहुलमन्यत्रापि' । युच्स्यात् । स्यन्दनः । रोचना । २३७ 'रञ्जेः क्युन्' । रजनम् । २३८ 'भूसूधूभ्रस्जिभ्यश्छन्दसि' । भुवनम् । सुवन आदित्यः । धुवनो वह्निः । निधुवनं सुरतम् । भृज्जनमम्बरीषम् । २३९ 'कृपृवृजिमन्दिनिधाञः क्युः' । किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् । २४० 'धृषेर्धिष च संज्ञायाम्' । धिषणो गुरुः । धिषणा धीः । २४१ 'वर्तमाने पृषद्बृहन्महज्जगच्छतृवत्' । अतिप्रत्ययान्ताः । 'पृषु सेचने' गुणाभावः । पृषन्ति । बृहत् । महान् । गमेर्जगादेशः । जगत् । २४२ 'संश्चत्तृपद्वेहत्' । एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुट् । इकारलोपः । संश्चत्कुहकः । तृपच्छत्रम् । विपूर्वाद्धन्तेष्टिलोपः इत ए च । 'वेहद्गर्भोपघातिनी' । २४३ 'छन्दस्यसानच्शुजॄभ्याम्' । शवसानः पन्थाः । जरसानः पुरुषः । २४४ 'ऋञ्जिवृधिमन्दिसहिभ्यः कित्' । ऋञ्जसानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च । २४५ 'अर्तेर्गुणः शुट् च' । अर्शसानोऽग्निः । २४६ 'सम्यानच्स्तुवः' । संस्तवानो वाग्मी । २४७ 'युधिबुधिदृशिभ्यः किच्च' । युधानः । बुधानः । दृशानो लोकपालकः । २४८ 'हुरेः सनो लुक् श्लोपश्च' । जुहुराणश्चन्द्रमाः । २४९ 'श्वितेर्दश्च' । शिश्विदानः पुण्यकर्मा । २५० 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ' । शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तः । तौ चानिटौ । शंस्ता स्तोता । शंस्तारौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेत् । 'वृक्ये चक्षदानम्' इति मन्त्रात् । 'उक्षाणं वा वेहतं वा क्षदन्ते' इति ब्राह्मणाच्च । 'क्षत्ता स्यात्सारथौ द्वाःस्थे वैश्यायामपि शूद्रजे' । २५१ 'बहुलमन्यत्रापि' । मन् । मन्ता । हन् । हन्ता । इत्यादि । २५२ 'नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रा-

तृजन्ता नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ'। न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च। नयतेः षुग्गुणश्च। नेष्टा। त्विषेरितोऽत्त्वम्। त्वष्टा। होता। पोता ऋत्विग्भेदः। भ्राजतेर्जलोपः। भ्राता। जायां माति जामाता। 'मान पूजायाम्' नलोपः। माता। पातेराकारस्येत्त्वम्। पिता। दुहेस्तृच इट् गुणाभावश्च। दुहिता। २५३ 'साविसेकन्'। स्वसा। २५४ 'यतेर्वृद्धिश्च'। याता। 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्'। २५५ 'नाञि च नन्देः'। न नन्दति ननान्दा। इह वृद्धिर्नानुवर्तत इत्येके। 'ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सा' इति शब्दार्णवः। २५६ 'दिवेर्ऋः'। देवा। देवरः। 'स्वामिनो देवृदेवरौ'। २५७ 'नयतेर्डिच्च'। ना। नरौ। नरः। २५८ 'सव्ये स्थश्छन्दसि'। 'अम्बाम्ब-' (सू २९१८) इत्यत्र 'स्थास्थिन्स्थृणामुपसंख्यानम्' (वा ४९६१) सव्येष्ठा सारथिः। सव्येष्ठारौ। सव्येष्ठरः। २५९ 'अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः'। अष्टभ्योऽनिप्रत्ययः स्यात्। अरणिर्योनिः। सरणिः। धरणिः। धमनिः। अमनिर्गतिः। अशनिः। अवनिः। तरणिः। बाहुलकाद्रजनिः। २६० 'आङि शुषेःसनश्छन्दसि'। आशुशुक्षणिरग्निर्वातश्च। २६१ 'कृषेरादेश्च चः'। चर्षणिर्जनः। २६२ 'अदेर्मुट् च'। अद्मनिरग्निः। २६३ 'वृतेश्च'। वर्तनिः। गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह। २६४ 'क्षिपेः किच्च'। क्षिपणिरायुधम्। २६५ 'अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः'। अर्चिर्ज्वाला। इदन्तोऽप्ययम्। 'अग्नेर्भ्राजन्ते अर्चयः'। शोचिर्दीप्तिः। हविः सर्पिः। 'इस्मन्-' (सू२९८५) इति ह्रस्वः। छदिः पटलम्। छर्दिर्वमनव्याधिः। इदन्तोऽपि। 'छर्दतीसारशूलवान्'। २६६ 'बृंहेर्नलोपश्च'। 'बर्हिर्ना कुशशुष्मणोः'। २६७ 'द्युतेरिसिन्नादेश्च जः'। ज्योतिः। २६८ 'वसौ रुचेः संज्ञायाम्'। वसुरोचिर्यज्ञः। २६९ 'भुवः कित्'। भुविः समुद्रः। २७० 'सहो धश्च'। सधिरनड्वान्। २७१ 'पिबतेस्थुक्'। 'पाथिश्चक्षुः समुद्रयोः'। २७२ 'जनेरुसिः'। जनुर्जननम्। २७३ 'मनेर्धश्छन्दसि'। मधुः। २७४ 'अर्तिपृवपियजितनिधनितपिभ्यो नित्'। अरुः। परुर्ग्रन्थिः। वपुः। यजुः। तनुः। तनुषी। तनूंषि। धनुरस्त्रियाम्। 'धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति'। सान्तस्योदन्तस्य वा रूपम्। 'तपुः सूर्याग्निशत्रुषु'। २७५ 'एतेर्णिच्च'। आयुः। आयुषी। २७६ 'चक्षेः शिच्च'। चक्षुः। २७७ 'मुहेः किच्च'। मुहुरव्ययम्। २७८ 'बहुलमन्यत्रापि'। आचक्षुः। परिचक्षुः। २७९ 'कृगॄशॄवृञ्चतिभ्यः ष्वरच्'। 'कर्बरो व्याघ्ररक्षसोः'। गर्वरोऽहंकारी। शर्वरी रात्रिः। 'वर्वरः प्राकृतो जनः'। चत्वरम्। २८० 'नौ सदेः'। 'निषद्वरस्तु जम्बालः'। निषद्वरी रात्रिः इत्युणादिषु द्वितीयः पादः।

२८१ 'छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः'। एकादश ष्वरच्प्रत्ययान्ता निपात्यन्ते। 'छिदिर्' 'छद्' अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च। छित्वरो धूर्तः। 'छत्वरो गृहकुञ्जयोः'। धीवरः कैवर्तः। पीवरः स्थूलः। मीवरो हिंसकः। चिनोतेर्दीर्घश्च। चीवरं भिक्षुप्रावरणम्। तीवरो जातिविशेषः। नीवरः परिव्राट्। गाहतेर्ह्रस्वत्वम्। गह्वरम्। कटे वर्षादौ कट्वरं व्यञ्जनम्। यमेर्दकारः संयद्वरो नृपः। पदे संपद्वर इत्येके। २८२ 'इण्सिञ्जिदीङुष्यविभ्यो नक्'। 'इनः सूर्ये नृपे पत्यौ' सिनः काणः। जिनोऽर्हन्। दीनः उष्णः। ऊनः। २८३ 'फेनमीनौ'। एतौ निपात्येते। स्फायतेः फेनः। मीनः। २८४ 'कृषेर्वर्णे'। कृष्णः। २८५ 'बन्धेर्ब्रधिबुधी च' ब्रध्नः। बुध्नः। २८६ 'धाप्वस्यज्यतिभ्यो

नः'। 'धाना भृष्टयवे स्त्रियः'। पर्णं पत्रम्। पर्णः किंशुकः। 'वस्नो मूल्ये वेतने च'। अजेर्वी। श्रोणः पङ्गुः।२८७ 'लक्षेरट् च'। लक्षेर्मुडागमश्च। अल्न आदित्यः। बाहुलकाच्छृगोतेः। श्रोणः पङ्गुः।२८७ 'लक्षेरट् च'। लक्षेर्मुरा- ण्यन्तान्नः स्यात्तस्याडागमश्च। चान्मुडित्येके। 'लक्षणं लक्ष्मणं नाम्नि चिह्ने च'। लक्षणो लक्ष्मणश्च रामभ्राता। 'लक्षणाहंसयोषायां सारसस्य च लक्ष्मणा'। २८८ 'वनेरिच्चोपधायाः'। वेणा नदी। २८९ 'सिवेष्टेर्यू च'। दीर्घोच्चारणसामर्थ्यान्न गुणः। स्यून आदित्यः। बाहुलका- त्केवलो नः। ऊट्। अन्तरङ्गत्वाद्यण्। गुणः। स्योनः। २९० 'कृवृजृसिद्रुपन्यनिस्वापिभ्यो नित्'। कर्णः। वर्णः। 'जर्णश्चन्द्रे च वृक्षे च'। सेना। द्रोणः। पन्नो नीचैर्गतिः। अन्नमो- दनः। स्वप्नो निद्रा। २९१ 'धेट इच्च'। धेनः सिन्धुर्नदी धेना'। २९२ 'तृषिशुषिरसिभ्यः कित्'। तृष्णा। शुष्णः सूर्यो वह्निश्च। रस्नं द्रव्यम्। २९३ 'सुञो दीर्घश्च'। सूना वध- स्थानम्। २९४ 'रमेस्त च'। रमयतीति रत्नम्। २९५ 'रास्नासास्नास्थूणावीणाः'। रास्ना गन्धद्रव्यम्। सास्ना गोगलकम्बलः। स्थूणा गृहस्तम्भः। वीणा वल्लकी। २९६ 'गादा- भ्यामिष्णुच्'। गेष्णुर्गायनः। देष्णुर्दाता। २९७ 'कृत्यशूभ्यां क्स्नः'। कृत्स्नम्। अक्ष्णम- खण्डम्। २९८ 'तिजेर्दीर्घश्च'। तीक्ष्णम्। २९९ 'श्लिषेरच्चोपधायाः'। श्लक्ष्णम्। ३०० 'यजिमनिशुन्धिदसिजनिभ्यो युच्'। यज्युरध्वर्युः। 'मन्युर्दैन्ये क्रतौ क्रुधि'। शुन्ध्युरग्निः। दस्यु- स्तस्करः। जन्युः शरीरी। ३०१ 'भुजिमृङ्भ्यां युक्त्युकौ'। भुज्युर्भाजनम्। मृत्युः। ३०२ 'सर्तेरयुः'। सरयुर्नदी। अयूरिति पाठान्तरम्। सरयूः। ३०३ 'पानीविषिभ्यः पः'। पाति रक्षत्यस्मादात्मानमिति पापम्। तद्योगात्पापः। नेपः पुरोहितः। बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः। वेष्पः पानीयम्। ३०४ 'च्युवः किच्च'। च्युपो वक्त्रम्। ३०५ 'स्तुवो दीर्घश्च'। स्तूपः समुच्छ्रायः। ३०६ 'सुशृभ्यां निच्च'। चात्कित्। सूपः। बाहुलकादूत्त्वम्। शूर्पम्। ३०७ 'कुयुभ्यां च'। कुवन्ति मण्डूका अस्मिन्कूपः। युवन्ति बध्नन्त्यस्मिन्पशुमिति यूपो यज्ञ- स्तम्भः। ३०८ 'खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः'। सप्तैते पप्रत्ययान्ता निपात्यन्ते। खनतेर्नकारस्य षत्वम्। 'खष्पौ क्रोधबलात्कारौ'। शीलतेर्ह्रस्वश्च। शिल्पं कौशलम्। 'शसु' हिंसायाम्। निपातनात्षत्वम्। शष्पं बालतृणं प्रतिभाक्षयश्च। बाधतेः षः। 'बाष्पो नेत्रज- लोष्मणोः'। बाष्पं च। रौतेर्दीर्घः। 'रूपं स्वभावे सौन्दर्ये'। पॄ। पर्पं गृहं बालतृणं पङ्गुपीठं च। 'तल प्रतिष्ठाकरणे' चुरादिणिचो लुक्। 'तल्पं शय्याट्टदारेषु'। ३०९ 'स्तनिहृषिपुषिग- दिमदिभ्यो णेरित्नुच्'। 'अयामन्त-' (सू २३११) इति णेरयादेशः। स्तनयित्नुः। हर्षयित्नुः। पोषयित्नुः। गदयित्नुर्वावदूकः। मदयित्नुर्मदिरा। ३१० 'कृहनिभ्यां क्त्नुः'। कृत्नुः शिल्पी। हत्नुर्व्याधिः शस्त्रं च। ३११ 'गमेः सन्वच्च'। जिगत्नुः। ३१२ 'दाभाभ्यां नुः'। दानुर्दाता। भानुः। ३१३ 'वच्चेर्गश्च'। वग्नुः। ३१४ 'धेट इच्च'। धयन्ति तामिति धेनुः। ३१५ 'सुवः कित्'। 'सूनुः पुत्रेऽनुजे रवौ'। ३१६ 'जहातेर्द्वेऽन्तलोपश्च'। जह्नुः। ३१७ 'स्थो णुः'। 'स्थाणुः कीले स्थिरे हरे'। ३१८ 'आजिवृरीभ्यो निच्च' अजेर्वी। वेणुः। वर्णुर्नददेशभेदयोः। 'रेणुर्द्वयोः स्त्रियां धूलिः'। ३१९ 'विषेः किच्च'। विष्णुः। ३२० 'कृदाधाराचिंकलिभ्यः कः'। बाहुलकान्न कस्येत्संज्ञा। 'कर्को धवलघोटकः'। दाको दाता। धाकोऽनड्वानाधारश्च। राका पौर्णमासी। अर्कः। 'कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि'। ३२१ 'सृवृभूशुषिमुषिभ्यः कक्'। 'सृक उत्प- लवातयोः'। 'वृकः श्वापदकाकयोः'। भूकं छिद्रम्। शुष्कः। मुष्कोऽण्डम्। ३२२

'शुकवल्कोल्काः'। शुभेरन्त्यलोपः। शुकः। 'वल्कं वल्कलमस्त्रियाम्'।'उष दाहे'। षस्य लः। उल्का। ३२३ 'इण्भीकापाशल्यतिमर्चिभ्यः कन्'। 'एके मुख्यान्यकेवलाः'। 'भेको मण्डूकमेघयोः' इति विश्वमेदिन्यौ। काकः। पाकः शिशुः। शल्कं शकलम्। अत्कः पथिकः शरीरावयवश्च। मर्कः शरीरवायुः। ३२४ 'नौ हः'। जहातेः कन्स्यान्नौ। निहाका गोधिका। ३२५ 'नौ सदेर्डिच्च'। 'निष्कोऽस्त्री हेम्नि तत्पले'। ३२६ 'स्यमेरीट् च'। स्यमीको वल्मीकः वृक्षभेदश्च। इट् ह्रस्व इति केचित्। स्यमिकः। ३२७ 'अजियुधुनीभ्यो दीर्घश्च'। 'वीकः स्याद्वातपक्षिणोः'। यूका। धूको वायुः। नीको वृक्षविशेषः। ३२८ 'ह्रियो रश्च लो वा'। 'ह्रीका ह्लीका त्रपा मता'। ३२९ 'शकेरुनोन्तोन्त्युनयः'। 'उन' 'उन्त' 'उन्ति' 'उनि' एते चत्वारः स्युः। शकुनः। शकुन्तः। शकुन्तिः। शकुनिः। ३३० 'भुवो झिच्'। भवन्तिर्वर्तमानकालः। बाहुलका[१]-द्वेश्च। अवन्तिः। वदेर्वदन्तिः। 'किंवदन्ती जनश्रुतिः'। ३३१ 'कन्युच्क्षिपेश्च'। चाद्भुवः। 'क्षिपण्युर्वसन्तः' इत्युज्ज्वलदत्त। 'भुवन्युः स्वामिसूर्ययोः'। ३३२ 'अनुङ् नदेश्च'। चात्क्षिपेः। नदनुर्मेघः। क्षिपणुर्वातः। ३३३ 'कृवृदारिभ्य उनन्'। 'करुणो वृक्षभेदः स्यात्करुणा च कृपा मता'। वरुणः। दारुणम्। ३३४ 'त्रो रश्च लो वा'। 'तरुणस्तलुनो युवा'। ३३५ 'क्षुधिपिशिमिथिभ्यः कित्'। क्षुधुनो म्लेच्छजातिः। पिशुनः। मिथुनम्। ३३६ 'फलेर्गुक्च'। फल्गुनः पार्थः। प्रज्ञाद्यण्। फाल्गुनः। ३३७ 'अशेर्लशश्च'। लशुनम्। ३३८ 'अर्जेर्णिलुक्च'। अर्जुनः। ३३९ 'तृणाख्यायां चित्'। चित्त्वादन्तोदात्तः। अर्जुनं तृणम्। ३४० 'अर्तेश्च'। अरुणः। ३४१ 'अजियमिशीङ्भ्यश्च'। वयुनं देवमन्दिरम्'। यमुना। शयुनोऽजगरः। ३४२ 'वृतृवदिहनिकमिकषिभ्यः सः'। वर्षम्। 'तर्षः प्लवसमुद्रयोः'। वत्सः। वत्सं वक्षः। हंसः। कंसोऽस्त्री पानभाजनम्'। कक्षं नक्षत्रम्। ३४३ 'प्लुषिरञ्चोपधायाः'। प्लक्षः। ३४४ 'मनेर्दीर्घश्च'। मांसम्। ३४५ 'अशेर्देवने'। अक्षः। ३४६ 'स्नुव्रश्चिकृत्यृषिभ्यः कित्'। स्नुषा। वृक्षः। कृत्समुदकम्। ऋक्षं नक्षत्रम्। ३४७ 'ऋषेर्जातौ'। 'ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने। ऋक्षमुक्तं च नक्षत्रे' इति विश्वः। ३४८ 'उन्दिगुधिकुषिभ्यश्च'। उत्सः प्रस्रवणम्। गुत्सः स्तबकः। कुक्षी जठरम्। ३४९ 'गृधिपण्योर्दकौ च'। गृत्सः कामदेवः। पक्षः। ३५० 'अशेः सरः'। अक्षरम्। ३५१ 'वसेश्च'। वत्सरः। ३५२ 'संपूर्वाच्चित्'। संवत्सरः। ३५३ 'कृधुमदिभ्यः कित्'। बाहुलकान्न षत्वम्। 'कृसरः स्यात्तिलौदनम्'। धूसरः। मत्सरः। 'मत्सरा मक्षिका ज्ञेया भंभराली च सा मता'। ३५४ 'पते रश्च लः'। पत्सलः पन्थाः। ३५५ 'तन्यृषिभ्यां क्सरन्'। तसरः सूत्रवेष्टने। ऋक्षरः ऋत्विक्। ३५६ 'पीयुक्वणिभ्यां कालन्ह्रस्वः संप्रसारणं च'। पीयुः सौत्रः। पियालो वृक्षभेदः। कुणालो देशभेदः। ३५७ 'कटिकुषिभ्यां काकुः'। कटाकुः पक्षी। कुषाकुरग्निः सूर्यश्च। ३५८ 'सर्तेर्दुक्च'। 'सृदाकुर्वातसरितोः'। ३५९ 'वृतेर्वृद्धिश्च'। वार्ताकुः। बाहुलकादुकारस्यात्त्वम्। वार्ताकम्। ३६० 'पर्देर्नित्संप्रसारणमल्लोपश्च'। 'पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे'। ३६१ 'सृयुवचि-

१ अतएव 'पयः पृषन्तिभिः पृक्ता वान्ति वाताः शनैः शनैः' इति पाणिनिप्रयोगे मुकुटदर्शित उपपद्यते।

भ्योऽम्भूजागूजक्रचः' । अन्युजागूजक्रुजेते क्रमात्स्युः । 'सरण्युर्मेघवातयोः' । यवागूः ।
'वचकुविप्रवाग्मिनोः' । ३६२ 'आनकः शीङ्भियः' । शयानकोऽजगरः । भयानकः । ३६३
'आणको लुधुशिङ्घिधाभ्यः' । लवाणकं दात्रम् । धवाणको वातः । शिङ्घाणकः श्लेष्मा ।
पृषोदरादित्वात्पक्षे कलोपः । 'शिङ्घाणं नासिकामले' । 'धाणको दीनारभागः' । ३६४ 'उल्मु-
कदर्विहोमिनः' । उष दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेर्विः ।
दर्विः । 'जुहोतेर्मिनिः' । होमी । ३६५ 'ह्रियः कुक्रश्च लो वा' । ह्रीकुर्ह्लीकुर्लज्जावान् । ३६६
'हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन्' । दशभ्यस्तन्स्यात् । 'तितुत्र–' (सू ३१६३) इति नेट् ।
हस्तः । मर्तः । गर्तः । एतः कर्बुरः । वातः । अन्तः । दन्तः । 'लोत स्यादश्रुचिह्नयोः' । 'पोतो
बालवहित्रयोः' । बाहुलकात्तुसेर्दीर्घश्च । तूस्तं पापं धूलिर्जटा च । ३६७ 'नञ्याप इट् च' ।
नापितः । ३६८ 'तनिमृङ्भ्यां किच्च' । ततम् । मृतम् । ३६९ 'अञ्जिघृसिभ्यः क्तः' । अक्तम् ।
घृतम् । सितम् । ३७० 'दुतनिभ्यां दीर्घश्च' । दूतः । तातः । ३७१ 'जेर्मूट् चोदात्तः' । जीमूतः ।
३७२ 'लोष्टपलितौ' । लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् । पलितम् । ३७३
'हृश्याभ्यामितन्' । हरितश्येतौ वर्णभेदौ । ३७४ 'रुहे रश्च लो वा' । 'रोहितो मृगमत्स्ययोः' ।
लोहितं रक्तम् । ३७५ 'पिशेः किच्च' । पिशितं मांसम् । ३७६ 'श्रुदक्षिस्पृहिगृहिभ्य आय्यः' ।
श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी । ३७७
'दिधिषाय्यः' । दधातेर्द्वित्वमित्वं षुक्च । 'मित्र इव यो दिधिषाय्यः' । ३७८ 'वृञ एण्यः' ।
वरेण्यः । ३७९ 'स्तुवः वसेय्यश्छन्दसि' । 'स्तुषेय्यं पुरुवर्चसम्' । ३८० 'राजेरन्यः' ।
राजन्यो वह्निः । ३८१ 'शॄरम्योश्च' । शरण्यम् । रमण्यम् । ३८२ 'अर्तेर्निच्च' । अरण्यम् । ३८३
'पर्जन्यः' । 'पृषु सेचने' । षस्य जः । 'पर्जन्यः शक्रमेघयोः' । ३८४ 'वदेरान्यः' । 'वदान्य-
स्त्यागिवाग्मिनोः' । ३८५ 'अमिनक्षियजिवधिपतिभ्योऽत्रन्' । अमत्रं भाजनम् । नक्षत्रम् ।
यजत्रः । वधत्रमायुधम् । पतत्रं तनूरुहम् । ३८६ 'गडेरादेश्च कः' । कडत्रम् । डलयोरेकत्व-
स्मरणात्कलत्रम् । ३८७ 'वृञश्चित्' । वरत्रा चर्ममयी रज्जुः । ३८८ 'सुविदेः कत्रन्' । 'सुवि-
दत्रं कुटुम्बकम्' । ३८९ 'कृतेर्नुम्च' । कृन्तत्रं लाङ्गलम् । ३९० 'भृमृदृशियजिपर्विपच्यमित-
मिनमिहर्यभ्योऽतच्' । दशभ्योऽतच्स्यात् । भरतः । मरतो मृत्युः । 'दर्शतः सोमसूर्ययोः' । यजत
ऋत्विक् । पर्वतः । पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ।
३९१ 'पृषिरञ्जिभ्यां कित्' । पृषतो मृगो बिन्दुश्च । रजतम् । ३९२ 'खलतिः' । स्खलतेः
सलोपः । अतच्प्रत्ययान्तस्येत्वं च । खलतिर्निष्केशशिराः । ३९३ 'शीङ्शपिरुगमिवञ्चि-
जीविप्राणिभ्योऽथः' । सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः ।
गमथः पथिकः पन्थाश्च । वञ्चथो धूर्तः । वन्दीति पाठे वन्दते वन्द्यते वा वन्दथः स्तोता
स्तुत्यश्च । जीवथ आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । 'शमथस्तुशमः
शान्तिर्दान्तिस्तु दमथो दमः' । ३९४ 'भृञश्चित्' । भरथो लोकपालः । ३९५ 'रुदिविदिभ्यां
ङित्' । रोदितीति रुदथः शिशुः । वेत्तीति विदथः । ३९६ 'उपसर्गे वसेः' । आवसथो गृहम् ।
संवसथो ग्रामः । ३९७ 'अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्' ।
त्रयोदशभ्योऽसच्स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चम-
त्यस्मिन्श्चमसः सोमपानपात्रम् । ताम्यत्यस्मिन्निति तमसोऽन्धकारः । नमसोऽनुकूलः ।

'रभसो वेगहर्षयोः'। लभसो धनं याचकश्च। नभति नभ्यति वा नभस आकाशः। तपसः पक्षी चन्द्रश्च। पतसः पक्षी। 'पनसः कण्टकिफलः'। पणसः पण्यद्रव्यम्। महसं ज्ञानम्। ३९८ 'वेञस्तुट् च'। बाहुलकादात्वाभावः। वेतसः। ३९९ 'वहियुभ्यां णित्'। वाहसोऽजगरः। यावसस्तृणसंघातः। ४०० 'वयश्च'। वय गतौ। वायसः काकः। ४०१ 'दिवः कित्'। दिवसं-दिवसश्च। ४०२ 'कृशृशलिकलिगर्दिभ्योऽभच्'। करभः। शरभः। शलभः। कलभः। गर्दभः। ४०३ 'ऋषिवृषिभ्यां कित्'। ऋषभः। वृषभः। ४०४ 'रुषेर्नित्लुक्च'। 'रुष हिंसायाम्'। अस्मादभच्निन्त्कित्स्यात्, लुषादेशश्च। 'लुषभो मत्तदन्तिनि'। ४०५ 'रासिवल्लिभ्यां च'। रासभः। वल्लभः। ४०६ 'जॄविशिभ्यां झच्'। जरन्तो महिषः। वेशन्तः पल्वलम्। ४०७ 'रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि'। रोहन्तो वृक्षभेदः। नन्दन्तः पुत्रः। जीवन्त औषधम्। प्राणन्तो वायुः। षित्त्वान्ङीष्। रोहन्ती। ४०८ 'तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च'। दशभ्यो झच्स्यात्। स च षित्। तरन्तः समुद्रः। तरन्ती नौका। भवन्तः कालः। वहन्तो वायुः। वसन्त ऋतुः। भासन्तः सूर्यः। साधन्तो भिक्षुः। गडेर्घटादित्वान्मित्त्वं ह्रस्वः। 'अयामन्त-' (सू २३११) इति णेरयः। गण्डयन्तो जलदः। मण्डयन्तो भूषणम्। जयन्तः शक्रपुत्रः। नन्दयन्तो नन्दकः। ४०९ 'हन्तेर्मुट् हि च'। हेमन्तः। ४१० 'भन्देर्नलोपश्च'। भदन्तः प्रव्रजितः। ४११ 'ऋच्छेररः'। ऋच्छरा वेश्या। बाहुलकाज्जर्जरझर्झरादयः। ४१२ 'अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित्'। षड्भ्योऽरश्चित्स्यात्। अररं कपाटम्। कमरः कामुकः। भ्रमरः। चमरः। देवरः। वासरः। ४१३ 'कुवः क्ररन्'। कुररः पक्षिभेदः। ४१४ 'अङ्गिमदिमन्दिभ्य आरन्'। अङ्गारः। मदारो वराहः। 'मन्दारः पारिजातकः'। ४१५ 'गडेः कड च'। कडारः। ४१६ 'शृङ्गारभृङ्गारौ'। शृभृभ्यामारन्नुम्गुक् ह्रस्वश्च। शृङ्गारो रसः। भृङ्गारः कनकालुका। ४१७ 'कञ्जिमृजिभ्यां चित्'। कञ्जिः सौत्रः। कञ्जारो मयूरः। मार्जारः। ४१८ 'कमेः किदुच्चोपधायाः'। चिदित्यनुवृत्तेरन्तोदात्तः। कुमारः। ४१९ 'तुषारादयश्च'। तुषारः। कासारः। सहार आम्रभेदः। ४२० 'दीङो नुट् च'। दीनारः सुवर्णाभरणम्। ४२१ 'सर्तेरपः षुक्च'। सर्षपः। ४२२ 'उषिकुटिदलिकचिखजिभ्यः कपन्'। 'उषपो वह्निसूर्ययोः'। कुटपो मानभाण्डम्। दलपः प्रहरणम्। कचपं शाकपत्रम्। खजपं घृतम्। ४२३ 'क्वणेः संप्रसारणं च'। कुणपम्। ४२४ 'कपश्चाक्रवर्मणस्य'। स्वरे भेदः। ४२५ 'विटपपिष्टपविशिपोलपाः' चत्वारोऽमी कपन्प्रत्ययान्ताः। 'विट शब्दे'। 'विटपः'। विशतेरादेः पः। प्रत्ययस्य तुट्। पत्वम्। पिष्टपं भुवनम्। विशतेः प्रत्ययादेरित्वम्। विशिपं मन्दिरम्। वलतेः संप्रसारणम्। 'उलपं कोमलं तृणम्'। ४२६ 'वृतेस्तिकन्'। वर्तिका। ४२७ 'कृतिभिदिलतिभ्यः कित्'। कृत्तिका। भित्तिका भित्तिः। लत्तिका गोधा। ४२८ 'इष्यशिभ्यां तकन्'। इष्टका। अष्टका। ४२९ 'इणस्तशन्तशसुनौ'। एतशो ब्राह्मणः। स एव एतशाः। ४३० 'वीपतिभ्यां तनन्'। 'वी गत्यादौ'। वेतनम्। पत्तनम्। ४३१ 'दृदलिभ्यां भः'। दर्भः। 'दल्भः स्याद्वृषिचक्रयोः'। ४३२ 'अर्तिगृभ्यां भन्'। अर्भः। गर्भः। ४३३ 'इणः कित्'। इभः। ४३४ 'असिसञ्जिभ्यां क्थिन्'। अस्थि। सक्थि। ४३५ 'प्लुषिकुषिशुषिभ्यः क्सिः'। प्लुक्षिर्वह्निः। कुक्षिः। शुक्षिर्वातः। ४३६ 'अशेर्नित्'। अक्षि। ४३७ 'इषेः क्सुः'। इक्षुः। ४३८ 'अवितॄस्तृतन्त्रिभ्य ईः'। 'अवीर्नारी रजस्वला'। तरीर्नौः। स्तरीर्धूमः। तन्त्रीर्वीणादे-

गुणः । ४३९ 'यापोः किद्द्वे च' । ययीरश्वः । 'पपीः स्यात्सोमसूर्ययोः' । ४४० 'लक्षेर्मुट् च' । लक्ष्मीः । इत्युणादिषु तृतीयः पादः ।

४४१ 'वातप्रमीः' । वातशब्द उपपदे माधातोरीप्रत्ययः । स च कित् । वातप्रमीः । अयं स्त्रीपुंसयोः । ४४२ 'ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यन्याङ्किकुयुकृशिभ्यः कत्निज्यतुजलिजिष्ठुजिष्ठ-जिसन्स्यनिथिनुल्यसासानुकः' । द्वादशभ्यः क्रमात्स्युः । अर्तेः कत्निच्, यण् । 'बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः' । तनोतेर्यतुच् । तन्यतुर्वायू रात्रिश्च । अञ्जेरलिच् । अञ्जलिः । वनेरिष्ठुच् । वनिष्ठुः स्थविरान्त्रम् । अञ्जेरिष्ठच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः । ४४३ 'श्रः करन्' । उत्तरसूत्रे किद्ग्रहणादिह ककारस्य नेत्त्वम् । शर्करा । ४४४ 'पुषः कित्' । पुष्करम् । ४४५ 'कलश्च' । पुष्कलम् । ४४६ 'गमेरिनिः' । गमिष्यतीति गमी । ४४७ 'आङि णित्' । आगामी । ४४८ 'भुवश्च' । भावी । ४४९ 'प्रे स्थः' । प्रस्थायी । ४५० 'परमे कित्' । परमेष्ठी । 'मन्थः' । मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः । मन्थाः । मन्थानौ । मन्थानः । ४५१ 'पतस्थ च' । पन्थाः । पन्थानौ । ४५२ 'खजेराकः' । खजाकः पक्षी । ४५३ 'बलाकादयश्च' । बलाका । शलाका । पताका । ४५४ 'पिनाकादयश्च' । पातेरित्त्वं नुम्च । 'क्लीबपुंसोः पिनाकः स्याच्छूलशंकरधन्वनोः' । 'तड आघाते' । तडाकः । ४५५ 'कषिदूषिभ्यामीकन्' । कषीका पक्षिजातिः । 'दूषिका नेत्रयोर्मलम्' । ४५६ 'अनिहृषिभ्यां किच्च' । अनीकम् । हृषीकम् । ४५७ 'चङ्कणः कङ्कणश्च' । 'कण् शब्दे' अस्माद्यङ्लुगन्तादीकन्धातोः कङ्कणादेशश्च । 'घण्टिकायां कङ्कणीका सैव प्रतिसरापि च' । ४५८ 'शॄपॄवृञां द्वे रुक्चाभ्यासस्य' । शर्शरीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः । ४५९ 'फर्फरीकादयश्च' । 'स्फुर स्फुरणे' । अस्मादीकन्धातोः फर्फरादेशः । फर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झर्झरीकं शरीरम् । तिन्तिडीको वृक्षभेदः । 'चरेर्नुम्च'(गण १९९) । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुण्डरीकं वादित्रम् । पुण्डरीको व्याघ्रोऽग्निर्दिग्गजश्च । ४६० 'ईषः किद्ध्रस्वश्च' । इषीका शलाका । ४६१ 'ऋजेश्च' । ऋजीकं उपहतः । ४६२ 'सर्तेर्नुम्च' । सृणीका लाला । ४६३ 'मृडः कीकन्कङ्कणौ' । मृडीको मृगः । मृडङ्कणः शिशुः । ४६४ 'अलीकादयश्च' । कीकन्नन्ता निपात्यन्ते । 'अल भूषणादौ' । अलीकं मिथ्या । विपूर्वाद्व्यलीकं विप्रियं खेदश्च । 'वलीकं पटलप्रान्ते' इत्यादि । ४६५ 'कॄतॄभ्यामीषन्' । करीषोऽस्त्री शुष्कगोमये । तरीषस्तारिता । ४६६ 'शॄपॄभ्यां किच्च' । शिरीषः । पुरीषम् । ४६७ 'अर्जेऋज च' । 'ऋजीषं पिष्टपचनम्' । ४६८ 'अम्बरीषः' । अयं निपात्यते । 'अबि शब्दे' । 'अम्बरीषः पुमान्भ्राष्ट्रम्' । अमरस्तु 'क्लीबेऽम्बरीषं भ्राष्ट्रो ना' । ४६९ 'कॄशॄपॄकटिपटिशौटिभ्य ईरन्' । करीरो वंशाङ्कुरः । शरीरम् । परीरं फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कण्टकः कामश्च । 'शौटीरस्त्यागिवीरयोः' । ब्राह्मणादित्वात्ष्यञ् । शौटीर्यम् । ४७० 'वशेः कित्' । उशीरम् । ४७१ 'कशेर्मुट् च' । कश्मीरो देशः । ४७२ 'कृञ उच्च' । कुरीरं मैथुनम् । ४७३ 'घसेः किच्च' । क्षीरम् । ४७४ 'गभीरगम्भीरौ' । गमेर्भः ।

पक्षे नुम्च। ४७५ 'विषा विहा'। स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्ययः। विषा बुद्धिः। विहा स्वर्गः। अव्यये इमे। ४७६ 'पच एलिमच्'। 'पचेलिमो वह्निरब्धयोः'। ४७७ 'शीङो धुक्लक्वलञ्वालनः'। चत्वारः प्रत्ययाः स्युः। शीधु मद्यम्। शीलं स्वभावः। शैवलः शैवालम्। बाहुलकाद्ध्रस्वपोऽपि। 'शैवालं शैवलो न स्त्री शेपालो जननीलिका'। ४७८ 'मृकणिभ्यामूकोकणौ'। मरूको मृगः। काणूकः काकः। ४७९ 'वलेरूकः'। वलूकः पक्षी उत्पलमूलं च। ४८० 'उलूकादयश्च'। वलेः संप्रसारणमूकश्च। 'उलूकाविन्द्रपेचकौ'। वावदूको वक्ता। भल्लूकः। 'शमेर्बुक्च' (गण २००)। शम्बूको जलशुक्तिः। ४८१ 'शालिमाण्डिभ्यामूकण्'। शालूकं कन्दाविशेषः। मण्डूकः। ४८२ 'नियो मिः'। नेमिः। ४८३ 'अर्तेरुच्च'। ऊर्मिः। ४८४ 'भुवः कित्'। भूमिः। ४८५ 'अश्नोते रश्च'। रश्मिः किरणो रज्जुश्च। ४८६ 'दल्मिः'। 'दल विशरणे'। दल्मिरिन्द्रायुधम्। ४८७ 'वीज्याज्वरिभ्यो निः'। बाहुलकाण्णत्वम्। 'वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे'। ज्यानिः। जूर्णिः। ४८८ 'सृवृषिभ्यां कित्'। सृणिरङ्कुशः। 'वृष्णिः क्षत्रियमेषयोः'। ४८९ 'अङ्गेर्नलोपश्च'। अग्निः। ४९० वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्'। वह्निः। श्रेणिः। श्रोणिः। योनिः। द्रोणिः। ग्लानिः। हानिः। तूर्णिः। बाहुलकान्म्लानिः। ४९१ 'घृणिपृश्निपार्ष्णिचूर्णिभूर्णि'। एते पञ्च निपात्यन्ते। घृणिः किरणः। स्पृशतेः सलोपः। पृश्निरल्पशरीरः। पृषेर्वृद्धिश्च। पार्ष्णिः पादतलम्। चरेरुपधाया ऊत्वम्। चूर्णिः कपर्दकशतम्। बिभर्तेरुत्त्वम्। भूर्णिर्धरणी। ४९२ 'वृदृभ्यां विन्'। वर्विर्घस्मरः। दर्विः। ४९३ 'जॄशॄस्तॄजागृभ्यः क्विन्'। जीर्विः पशुः। शीर्विर्हिंस्रः। स्तीर्विरध्वर्युः। जागृविर्नृपः। ४९४ 'दिवो द्वे दीर्घश्चाभ्यासस्य'। 'दीदिविः स्वर्गमोक्षयोः'। ४९५ 'कृविघृष्विछविस्थविकिकीदिवि'। कृविस्तन्तुवायद्रव्यम्। घृष्विर्वराहः। छास्थोर्ह्रस्वत्वं च। छविर्दीप्तिः। स्थविस्तन्तुवायः। दीव्यतेः किकीपूर्वात्। किकीदिविश्चाषः। बाहुलकाद्ध्रस्वदीर्घयोर्विनिमयः। 'चाषेण किकिदीविना'। ४९६ 'पातेर्डतिः'। पतिः। ४९७ 'शकेर्ऋतिन्'। शकृत्। ४९८ 'अमेरतिः'। अमतिः कालः। ४९९ 'वहिवस्यर्तिभ्यश्चित्'। वहतिः पवनः। 'वसतिर्गृहयामिन्योः'। अरतिः क्रोधः। ५०० 'अञ्चेः कौ वा'। अङ्कतिरञ्चतिर्वातः। ५०१ 'हन्तेरंह च'। हन्तेरतिः स्यादंहादेशश्च धातोः। हन्ति दुरितमनया अंहतिर्दानम्। 'प्रादेशनं निर्वपणमपवर्जनमंहतिः'। ५०२ 'रमेर्नित्'। 'रमतिः कालकामयोः'। ५०३ 'सूङः क्रिः'। सूरिः। ५०४ 'आदिशदिभूशुभिभ्यः क्रिन्'। अद्रिः। शद्रिः शर्करा। भूरि प्रचुरम्। शुभ्रिर्ब्रह्मा। ५०५ 'वङ्क्र्यादयश्च'। क्रिन्नन्ता निपात्यन्ते। वङ्क्रिर्वाद्यभेदो गृहदारु पार्श्वास्थि च। वप्रिः क्षेत्रम्। 'अंह्रिरङ्घ्रिश्च चरणः'। तदिः सौत्रो धातुः। तन्द्रिर्मोहः। बाहुलकान्नुणः। भेरिः। ५०६ 'राशदिभ्यां त्रिप्'। रात्रिः। शत्रिः कुञ्जरः। ५०७ 'अदेस्त्रिनिश्च'। चात्त्रिप्। अत्री। अत्रिणौ। अत्रिणः। अत्रिः। अत्री। अत्रयः। ५०८ 'पतेरत्रिन्'। पतत्रिः पक्षी। ५०९ 'मृकणिभ्यामीचिः'। मरीचिः। कणीचिः पल्लवो निनादश्च। ५१० 'श्वयतेश्चित्'। श्वयीचिर्व्याधिः। ५११ 'वेञो डिच्च'। वीचिस्तरङ्गः। नञ्समासेऽवीचिर्नरकभेदः। ५१२ 'ऋहनिभ्यामूषन्'। अरूषः सूर्यः। हनूषो राक्षसः। ५१३ 'पुर कुषन्'। 'पुर अग्रगमने'। पुरुषः। 'अन्येषामपि–' (सू. ३५३९) इति दीर्घः। पूरुषः। ५१४ 'पॄनहिकलिभ्य उषच्'। परुषम्।

नहुषः। कलुषम्। ५१५ 'पीयेरूषन्'। पीय इति सौत्रो धातुः। पीयूषम्। बाहुलकात्गुणे 'पीयूषोऽभिनवं पयः'।५१६ 'मस्जेर्नुम्च'। मञ्जूषा।५१७ 'गडेश्च'। गण्डूषः–गण्डूषा।५१८ 'अर्तेररुः'। अररुः शत्रुः। अररू। अररवः।५१९ 'कुटः किच्'। कुटरुर्वस्त्रगृहम्। किच्चप्रयो- जनं चिन्त्यम्।५२० 'शकादिभ्योऽटन्'। शकटोऽस्त्रियाम्।ककिर्गत्यर्थः। कङ्कटः संनाहः। देवटः शिल्पी। करट इत्यादि।५२१ 'कृकादिकडिकटिभ्योऽम्बच्'।करम्बं व्यामिश्रम्।'कदिकडी' सौत्रौ। कदम्बो वृक्षभेदः। कडम्बोऽग्रभागः। कटम्बो वादित्रम्।५२२ 'कदेर्णित्पाक्षिणि'। कादम्बः कलहंसः।५२३'कलिकर्योरमः'। कलमः। कर्दमः।५२४ 'कुणिपुल्योः किन्दच्'। 'कुण शब्दोपकरणयोः'। कुणिन्दः शब्दः। पुलिन्दो जातिविशेषः।५२५ 'कुपेर्वा वश्च'। कुपिन्द- कुविन्दो तन्तुवाये।५२६ 'नौ षञ्जेर्घथिन्'। निषङ्गथिरालिङ्गकः।५२७ 'उदर्तेश्चित्'। उदराथिः समुद्रः।५२८ 'सर्तेर्णिच्च'। सारथिः।५२९ 'खर्जिपिञ्जादिभ्य ऊरोलचौ'। खर्जूरः। कर्पूरः। वल्लूरं शुष्कमांसम्। पिञ्जूलं कुशवर्तिः। 'लङ्गेर्वृद्धिश्च' (गण २०१)। लाङ्गूलम्। कुसूलः। 'तमेर्वुग्वृद्धिश्च' (गण २०२)। ताम्बूलम्। 'शृणातेर्दुग्वृद्धिश्च' (गण२०३)।शार्दूलः। 'दुक्कोः कुक्च' (गण २०४)। दुकूलम्। कुकूलम्।५३० 'कुवश्चट्दीर्घश्च'। कूची चित्रलेख- निका।५३१ 'समीणः'। समीचः समुद्रः। समीची हरिणी।५३२ 'सिवेष्टेरूच'। सूचो दर्भाङ्कुरः। सूची।५३३ 'शमेर्बन्'। शम्बो मुसलम्।५३४ 'उल्बादयश्च'। बन्नन्ता निपात्यन्ते। 'उच समवाये'। चस्य लत्वं गुणाभावश्च। उल्बो गर्भाशयः। शुल्वं ताम्रम्। निम्बः। बिम्बम्।५३५ 'स्थः स्तोऽम्बजबकौ'। तिष्ठतेरम्बजबक एतौ स्तस्तादेशश्च। 'स्तम्बो गुच्छस्तृणादिनः'। स्तबकः पुष्पगुच्छः।५३६ 'शाशपिभ्यां ददनौ'। 'शादो जम्बा- लशष्पयोः'। शब्दः।५३७ 'अब्दादयश्च'। अवतीत्यब्दः। 'कौतेर्नुम्(च)' (गण २०५)। कुन्दः।५३८ 'वलिमलितनिभ्यः कयन्'। वलयम्। मलयः। तनयः।५३९ 'वृहोः षुग्दुकौ च'। वृषय आश्रयः। हृदयम्।५४० 'मिपीभ्यां रुः'। मेरुः। पेरुः सूर्यः। बाहुलकात्पिबतेरपि। 'संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः'।५४१ 'जत्र्वादयश्च'। जत्रु। जत्रुणी। अश्रु। अश्रुणी।५४२ 'रुशातिभ्यां क्रुन्'। रुरु- र्मृगभेदः। शातयतीति शत्रुः। प्रज्ञादौ पाठाद्ध्रस्वत्वम्।५४३ 'जनिदाच्युसृवृमदिषमिन- मिभृञ्भ्य इत्वन्त्वन्तन्णिक्न्शक्स्यढडटाटचः'। जनित्वौ मातापितरौ। दात्वो दाता। च्यौत्नो गन्ताण्डजः क्षीणपुण्यश्च। सृणिरङ्कुशश्चन्द्रः सूर्यो वायुश्च। वृश आर्द्रकं मूलकं च। मत्स्यः। षण्ढः। डित्त्वाट्टिलोपः। नमतीति नटः शैलूषः। बिभर्ति भरटः कुलालो भृतकश्च।५४४ 'अन्येभ्योऽपि दृश्यन्ते'। पेत्वममृतम्। भृशम्।५४५ 'कुसेरुम्भोमेदेताः'। कुसुम्भम्। कुसुमम्। कुसदिम्। कुसितो जनपदः।५४६ 'सानसिवर्णसिपर्णसितण्डुला- ङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः'। सनोतेरसिप्रत्यय उपधावृद्धिः। सानसिर्हिर- ण्यम्। वृञो नुक्च। वर्णसिर्जलम्। पॄ। पर्णसिर्जलगृहम्। 'तड आघाते'। तण्डुलाः। आकि लक्षण उशच्। अङ्कुशः। चषेरालच्। 'चषालो यूपकटकः'। इल्वलो दैत्यभेदः। पल्वलम्। ञिधृषा ण्यः। ऋकारस्येकारः। धिष्ण्यम्। शलेर्यः। 'शल्यं वा पुंसि शङ्कुर्नो'।५४७ 'मूशक्यविभ्यः क्लः'। मूलम्। शक्लः प्रियंवदे। अम्लो रसः। बाहुलकादमेः। अम्लः।५४८ 'माछाससिभ्यो यः'।

मांया । छाया । सस्यम् । बाहुलकात्सुनोतेः । 'सव्यं दक्षिणवामयोः' । ५४९ 'जनेर्यक्' । 'ये विभाषा' (सू. २३१९) । जन्यं युद्धम् । जाया भार्या । ५५० 'अघ्न्यादयश्च' । यगन्ता निपात्यन्ते । हन्तेर्यगडागम उपधालोपश्च । अघ्न्या माहेयी । अघ्न्यः प्रजापतिः । 'कनी दीप्तौ' । कन्या । बवयोरैक्यम् । वन्ध्या । ५५१ 'स्नामदिपद्यर्तिपृशकिभ्यो वनिप्' । स्नावा रसिकः । मद्वा शिवाः । पद्वा पन्थाः । 'अर्वा-तुरङ्गगर्ह्ययोः' । पर्व ग्रन्थिः प्रस्तावश्च । शक्वा हस्ती । ङीप्रौ । शक्वर्यङ्गुलिः । ५५२ 'शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप्' । शीवाजगरः । कुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः । ५५३ 'धाप्योः संप्रसारणं च' । धीवा कर्मकरः । पीवा स्थूलः । ५५४ 'अदेर्ध च' । अध्वा । ५५५ 'प्र ईरशदोस्तुट् च' । प्रेत्वा प्रशत्वा च सागरः । प्रेत्वरी प्रशत्वरी च नदी । ५५६ 'सर्वधातुभ्य इन्' । पचिरग्निः । तुडिः । तुण्डिः । वलिः । वटिः । देवयजिः । काशत इति काशिः । यतिः । मलिः । मल्ली । केलिः । 'मसी परिणामे' । मसिः । बाहुलकाद्गुणः । कोटिः । हेलिः । बोधिः । नन्दिः । कलिः । ५५७ 'हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च' । 'हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः' । पेषिर्वज्रम् । रोहिर्व्रती । वर्तिः । वेदिः । छेदिश्छेत्ता । कीर्तिः । ५५८ 'इगुपधात्कित्' । कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्द्वित्वे लिबिः । 'तूल निष्कर्षे' । तूलि । तूली कूर्चिका । ५५९ 'भ्रमेः संप्रसारणं च' । भृमिर्वातः । बाहुलकाद्भ्रमिः । ५६० 'क्रमितमिशतिस्तम्भामत इच्च' । क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । 'शितिर्मेचकशुक्लयोः' । स्तिम्भिः समुद्रः । ५६१ 'मनेरुच्च' । मुनिः । ५६२ 'वर्णेर्वलिश्चाहिरण्ये' । वर्णिः सौत्रः । अस्य बलिरादेशः । 'करोपहारयोः पुंसि बलिः प्राण्यङ्गके स्त्रियाम्' । हिरण्ये तु वर्णिः सुवर्णम् । ५६३ 'वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्' । 'वासिश्छेदनवस्तुनि' । वापिः—वापी । याजिर्यष्टा । राजिः—राजी । व्राजिर्वातालिः । सादिः सारथिः । निघातिर्लोहघातिनि । वाशिरग्निः । वादिर्विद्वान् । वारिर्गजबन्धनी । जले तु क्लीबम् । बाहुलकात् 'हारिः पथिकसंहतौ' । ५६४ 'नहो भश्च' । 'नाभिः स्यात्क्षत्रिये पुंसि' । प्राण्यङ्गे तु स्त्रियाम् । पुंस्यपीति केचित् । ५६५ 'कृषेर्वृद्धिश्छन्दसि' । कार्षिः । ५६६ 'श्रः शकुनौ' । शारिः । शारिका । ५६७ 'कृञ्र उदीचां कारुषु' । कारिः शिल्पी । ५६८ 'जनिघसिभ्यामिण्' । जनिर्जननम् । घासिर्भक्ष्यमग्निश्च । ५६९ 'अज्यतिभ्यां च' । आजिः संग्रामः । आतिः पक्षी । ५७० 'पादे च' । पदाजिः । पदातिः । ५७१ 'अशिपणाय्योरुडायलुकौ च' । अशेरुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः । ५७२ 'वातेर्डिच्च' । विः पक्षी । स्त्रियां वीत्यपि । ५७३ 'प्रे हरतेः कूपे' । प्रहिः कूपः । ५७४ 'नौ व्यो यलोपः पूर्वस्य च दीर्घः' । व्येञ इण्स्याद्यलोपश्च नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च । ५७५ 'समाने ख्यः स चोदात्तः' । समानशब्द उपपदे ख्या इत्यस्मादिण्स्यात् । स च डिच्च यलोपश्च समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैः इति सखा । ५७६ 'आङि श्रिहनिभ्यां ह्रस्वश्च' । इण्स्यात्स च डित् आङो ह्रस्वश्च । 'स्त्रियः पाल्यश्रिकोटयः' । 'सर्पे वृत्रासुरेऽप्यहिः' ।

५७८ 'अच इः'। रविः। पविः। तरिः। कविः। अरिः। अलिः। ५७९ 'खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च'। खनिः। कषिर्हिंस्रः। अजिः। असिः। वसिर्वस्त्रम्। वनिरग्निः। सनिर्भक्तिर्दानं च। ध्वनिः। ग्रन्थिः। चलिः। पशुः ५८०। 'वृतेश्छन्दसि'। वर्तिः। ५८१ 'भुजेः किच्च'। भुजिः। ५८२ 'कृगृशृपृकुटिभिदिछिदिभ्यश्च'। इः कित्स्यात्। किरिर्वराहः। 'गिरिर्गोत्राक्षिरोगयोः'। गिरिणा काणः गिरिकाणः। शिरिः शलभो हन्ता च। पुरिर्नगरं राजा नदी च। कुटिः शाला शरीरं च। भिदिर्वज्रम्। छिदिः परशुः। ५८३ 'कुडिकम्प्योर्नलोपश्च'। 'कुडि दाहे'। कुडिर्देहः। कपिः। ५८४ 'सर्वधातुभ्यो मनिन्'। क्रियत इति कर्म। चर्म। भस्म। जन्म। शर्म। स्थाम बलम्। 'इस्मन्–' (सू २९८५) इति ह्रस्वः। छद्म। सुत्रामा। ५८५ 'बृंहेर्नोऽच्च'। नकारस्याकारः। 'ब्रह्म तत्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः'। ५८६ 'अशिशकिभ्यां छन्दसि'। अश्मा। शक्मा। ५८७ 'हृभृधृसृस्तृशृभ्य इमनिच्'। हरिमा कालः। भरिमा कुटुम्बम्। धरिमा रूपम्। सरिमा वायुः। स्तरिमा तल्पम्। शरिमा प्रसवः। ५८८ 'जनिमृङ्भ्यामिमनिन्'। जनिमा जन्म। मरिमा मृत्युः। ५८९ 'वेञः सर्वत्र'। छन्दसि भाषायां चेत्यर्थः। वेमा तन्तुवायदण्डः। अर्धर्चादिः। सामनी वेमनी इति वृत्तिः। ५९० 'नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्ध्मामन्'। सप्तामी निपात्यन्ते। म्नायतेऽनेनेति नाम। सिनोतेर्दीर्घः। सीमा। सीमानौ। सीमानः। पक्षे डाप्। सीमे। सीमाः। व्येञोऽन्त्यस्योत्वं गुणः। व्योम। रौतेः रोम। लोम। पाप्मा पापम्। ध्माम परिमाणं तेजश्च। ५९१ 'मिथुने मनिः'। उपसर्गक्रियासंबन्धो मिथुनम्। स्वरार्थमिदम्। सुशर्मा। ५९२ 'सातिभ्यां मनिन्मनिणौ'। स्यतीति साम। सामनी। आत्मा। ५९३ 'हनिमशिभ्यां सिकन्'। 'हंसिका हंसयोषिति'। मक्षिका। ५९४ 'कोररन्'। कवरः। ५९५ 'गिर उडच्'। गरुडः। ५९६ 'इन्देः कमिर्नलोपश्च'। इदम्। ५९७ 'कायतेर्डिमिः'। किम्। ५९८ 'सर्वधातुभ्यः ष्ट्रन्'। वस्त्रम्। अस्त्रम्। शस्त्रम्। 'इस्मन्–' (सू २९८५) इति ह्रस्वत्वम्। छादनाच्छत्रम्। ५९९ 'भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च'। भ्राष्ट्रः। गान्त्रं शकटम्। नान्त्रं स्तोत्रम्। हान्त्रं भरणम्। वैष्ट्रं पिष्टपम्। आष्ट्रमाकाशम्। ६०० 'दिवेर्द्युच'। द्यौत्रं ज्योतिः। ६०१ 'उषिखनिभ्यां कित्'। उष्ट्रः। खात्रं खनित्रं जलाधारश्च। ६०२ 'सिविमुच्योष्टेरूच'। सूत्रम्। मूत्रम्। ६०३ 'अमिचिमिदिशसिभ्यः क्त्रः'। अन्त्रम्। चित्रम्। मित्रम्। शस्त्रम् ६०४ 'पुवो ह्रस्वश्च'। पुत्रः। ६०५ 'स्त्यायतेर्ड्रट्'। स्त्री। ६०६ 'गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः'। 'गोत्रं स्यान्नामवंशयोः'। गोत्रा पृथीवी। धर्त्रं गृहम्। वेत्रम्। पक्त्रम्। वक्त्रम्। यन्त्रम्। सत्त्रम्। क्षत्त्रम्। ६०७ 'हुयामाश्रुभसिभ्यस्त्रन्'। होत्रम्। यात्रा। मात्रा। श्रोत्रम्। भस्त्रा। ६०८ 'गमेरा च'। गात्रम्। ६०९ 'दादिभ्यश्छन्दसि'। दात्रम्। पात्रम्। ६१० 'भूवादिगृभ्यो णित्रन्'। भावित्रम्। वादित्रम्। गारित्रमोदनम्। ६११ 'चरेर्वृत्ते'। चारित्रम्। ६१२ 'अशित्रादिभ्य इत्रोत्रौ'। अशित्रम्। वहित्रम्। धरित्री मही। त्रैङ् एवमादिभ्य उत्रः। त्रोत्रं प्रहरणम्। वृञ्। वरुत्रं प्रावरणम्। ६१३ 'अमेर्द्विषाति चित्'। अमित्रः शत्रुः। ६१४ 'आ समिण्निकषिभ्याम्'। संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात्। स्वरादित्वादव्ययत्वम्। समया। निकषा। ६१५ 'चितेः कणः कश्च'। बाहुलकादगुणः। 'चिक्कणं मसृणं स्निग्धम्'। ६१६ 'सूचेः स्मन्'। सूक्ष्मम्। ६१७

'पातेर्डुम्सुन्' । पुमान् । ६१८ 'रुचिभुजिभ्यां किष्यन्' । रुचिष्यमिष्टम् । भुजिष्यो दासः । ६१९ 'वसेस्तिः' । 'वस्तिर्नाभेरधो द्वयोः' । 'वस्तयः स्युर्दशासूत्रे' । बाहुलकाच्छासः । शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः । ६२० 'सावसेः' । स्वस्ति । स्वरादिपाठादव्ययत्वम् । ६२१ 'वौ तसेः' । वितस्तिः । ६२२ 'पदिप्रथिभ्यां नित्' । पत्तिः । प्रथितिः । 'तितुत्रेष्वग्रहादीनाम्' (वा ४३९३) इतीट् । ६२३ 'दृणातेर्ह्रस्वश्च' । दृतिः । ६२४ 'कृतॄकृपिभ्यः कीटन्' । किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । 'कृपीटं कुक्षिवारिणोः' । ६२५ 'रुचिवचिकुचिकुटिभ्यः कितच्' । रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् । ६२६ 'कुटिकुषिभ्यां क्मलन्' । कुट्मलम् । कुष्मलम् । ६२७ 'कुषेर्लेश्च' । कुल्मलं पापम् । ६२८ 'सर्वधातुभ्योऽसुन्' । चेतः । सरः । पयः । सदः । ६२९ 'रपेरत एच्च' । रेपोऽवद्यम् । ६३० 'अशेर्देवने युट् च' । देवने स्तुतौ । यशः । ६३१ 'उब्जेर्बले बलोपश्च' । ओजः । ६३२ 'श्वेः संप्रसारणं च' । शवः । शवसी । बलपर्यायोऽयम् । ६३३ 'श्रयतेः स्वाङ्गे शिरः किच्च' । श्रयतेः शिरः आदेशोऽसुन्किच्च । शिरः । शिरसी । ६३४ 'अर्तेरुच्च' । उरः । ६३५ 'व्याधौ शुट् च' । अर्शो गुदव्याधिः । ६३६ 'उदके नुट् च' । अर्तेरसुन्स्यात्तस्य च नुट् । अर्णः । अर्णसी । ६३७ 'इण आगसि' । एनः । ६३८ 'रिचेर्धने घिच्च' । चात्प्रत्ययस्य नुट् । घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् । ६३९ 'चायतेरन्ने ह्रस्वश्च' । चनो भक्तम् । ६४० 'वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च' । वर्पो रूपम् । शेपो गुह्यम् । ६४१ 'स्रुरिभ्यां तुट् च' । स्रोतः । रेतः । ६४२ 'पातेर्बले जुट् च' । पाजः । पाजसी । ६४३ 'उदके थुट् च' । पाथः । ६४४ 'अन्ने च' । पाथो भक्तम् । ६४५ 'अदेर्नुम्धौ च' । अदेर्भक्ते वाच्येऽसुन्नुमागमो धादेशश्च । अन्धोऽन्नम् । ६४६ 'स्कन्देश्च स्वाङ्गे' । स्कन्धः—स्कन्धसी । ६४७ 'आपः कर्माख्यायाम्' । कर्माख्यायां ह्रस्वो नुट् च वा । अप्नः । अपः । बाहुलकात् । आपः । आपसी । ६४८ 'रूपे जुट् च' । अब्जो रूपम् । ६४९ 'उदके नुम्भौ च' । अम्भः । ६५० 'नर्योर्दिवि भश्च' । नभः । ६५१ 'इण आगोऽपराधे च' । 'आगः पापापराधयोः' । ६५२ 'अमेर्हुक्च' । अंहः । ६५३ 'रमेश्च' । रंहः । ६५४ 'देशेऽह च' । रमन्तेऽस्मिन्रहः । ६५५ 'अञ्च्यञ्जियुजिभृजिभ्यः कुश्च' । एभ्योऽसुन्कवर्गश्चान्तादेशः । 'अङ्कश्चिह्नशरीरयोः' । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः । ६५६ 'भूरञ्जिभ्यां कित्' । भुवः । रजः । ६५७ 'वसेर्णित्' । वासो वस्त्रम् । ६५८ 'चन्देरादेश्च छः' । छन्दः । ६५९ 'पचिवचिभ्यां सुट् च' । 'पक्षसी तु स्मृतौ पक्षौ' । वक्षो हृदयम् । ६६० 'वहिहाधाञ्भ्यश्छन्दसि' । वक्षा अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोः 'आतो युक्–' (सू २७६१)इति युक् । 'शोणा धृष्णू नृवाहसा' । 'श्रोता हवं गृणतः स्तोमवाहाः' । विश्वो विहायाः । 'वाजम्भरो विहायाः' । 'देवो नयः पृथिवीं विश्वधायाः' । 'अधारयत्पृथिवीं विश्वधायसम्' । 'धर्णसं भूरिधायसम्' इत्यादि । ६६१ 'इण आसिः' । अयाः वह्निः । स्वरादिपाठादव्ययत्वम् । ६६२ 'मिथुनेऽसिः पूर्ववच्च सर्वम्' । उपसर्गविशिष्टो धातुर्मिथुनं तत्रासुनोपवादोऽसिः स्वरार्थः । ६६३ 'नञि हन एह च' । अनेहा । अनेहसौ । ६६४ 'विधाञो वेध च' । विदधातीति वेधाः । ६६५ 'नुवो धुट् च' । नोधाः । ६६६ 'गतिकारकोपपदयोः

पूर्वपदप्रकृतिस्वरत्वं च' । असिः स्यात् । सुतपाः । जातवेदाः । 'गतिकारकोपपदात्कृत्' (सू ३८७६) इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् । ६६७ 'चन्द्रे मो डित्' । चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः । ६६८ 'वयसि धाञः' । वयोधास्तरुणः । ६६९ 'पयसि च' । पयोधाः समुद्रो मेघश्च । ६७० 'पुरसि च' । पुरोधाः । ६७१ 'पुरूरवाः' । पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते । ६७२ 'चक्षेर्बहुलं शिच्च' । नृचक्षाः । ६७३ 'उषः कित्' । उषः । ६७४ 'दमेरुनसिः' । 'सप्तार्चिर्दमुनाः' । ६७५ 'अङ्गतेरासिरिरुडागमश्च' । अङ्गिराः । ६७६ 'सर्तेरप्पूर्वादसिः' । अप्सराः । प्रायेणायं भूम्नि । अप्सरसः । ६७७ 'विदिभुजिभ्यां विश्वे' । विश्ववेदाः । विश्वभोजाः । ६७८ 'वशेः कनसिः' । संप्रसारणम् । उशनाः । इत्युणादिषु चतुर्थः पादः ।

६७९ 'अदि भुवो डुतच्' । अद्भुतम् । ६८० 'गुधेरूमः' । गोधूमः । ६८१ 'मसेरूरन्' । मसूरः । प्रथमे पादे असेरुरन् 'मसेश्च' इत्यत्र व्याख्यातः । ६८२ 'स्थः किच्च' । स्थूरो मनुष्यः । ६८३ 'पातेरातिः' । पातिः स्वामी । संपातिः पक्षिराजः । ६८४ 'वातेर्नित्' । 'वातिरादित्यसोमयोः' । ६८५ 'अर्तेश्च' । अरतिरुद्वेगः । ६८६ 'तृहेः क्नो हलोपश्च' । तृणम् ६८७ 'मृम्लुटितनिताडिभ्य उलच्तण्डश्च' । म्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः । ६८८ 'दंसेष्टटनौ न आ च' । 'दासः सेवकशूद्रयोः' । ६८९ 'दंशेश्च' । दाशो धीवरः । ६९० 'उदि चेर्डसिः' । स्वरादिपाठादव्ययत्वम् । उच्चैः । ६९१ 'नौ दीर्घश्च' । नीचैः । ६९२ 'सौ रमेः क्तो दमेः पूर्वपदस्य च दीर्घः' । रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्त्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च । ६९३ 'पूञो यण्णुक्ह्रस्वश्च' । यत्प्रत्ययः । पुण्यम् । ६९४ 'स्रंसेः शि कुट् किच्च' । स्रंसतेः शिरादेशो यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् । ६९५ 'अर्तेः क्युरुच्च' । उरणो मेषः । ६९६ 'हिंसेरीरन्नीरचौ' । हिंसीरो व्याघ्रदुष्टयोः । ६९७ 'उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च' । उदरम् । ६९८ 'डित्खनेर्मुट् स चोदात्तः' । अजल् च डित्स्याद्धातोर्मुट् स चोदात्तः । मुखम् । ६९९ 'अमेः सन्' । अंसः । ७०० 'मुहेः खो मूर् च' । मूर्खः । ७०१ नहेर्हलोपश्च' । नखः । ७०२ 'शीङो ह्रस्वश्च' । शिखा । ७०३ 'माङ ऊखो मय् च' । मयूखः । ७०४ 'कलिगलिभ्यां फगस्योच्च' । कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः । ७०५ 'स्पृशेः श्वण्शुनौ पृ च' । श्वण्शुनौ प्रत्ययौ 'पृ' इत्यादेशः । 'पार्श्वोऽस्त्री कक्षयोरधः' । पर्शुरायुधम् । ७०६ 'श्मनि श्रयतेर्डुन्' । श्मञ्छब्दो मुखवाची । मुखमाश्रयत इति श्मश्रुः । ७०७ 'अश्र्वादयश्च' । अश्रु नयनजलम् । ७०८ 'जनेष्टन्लोपश्च' । जटा । ७०९ 'अच्तस्य जङ्घ् च' । तस्य जनेर्जङ्घादेशः स्यादच् । जङ्घा । ७१० 'हन्तेः शरीरावयवे द्वे च' । जघनम् । 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' । ७११ 'क्लिशेरन्लो लोपश्च' । लकारस्य लोपः । केशः । ७१२ 'फलेरितजादेश्च पः' पलितम् । ७१३ 'कृञादिभ्यः संज्ञायां वुन्' । करकः—करका । कटकः । नरकम्—नरकः । 'नरको नारकोऽपि च' इति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च । ७१४ 'चीकयतेराद्यन्तविपर्ययश्च' । कीचको वंशभेदः । ७१५ 'पचिमच्योरिच्चोपधायाः' । पेचकः । मेचकः । ७१६ 'जनेरठ च' । जठरम् । ७१७ 'वचिमनिभ्यां चिच्च' । वठरो मूर्खः । 'मठरो मुनि-

शौण्डयोः'। बिदादित्वान्माठरः। गर्गादित्वान्माठर्यः। ७१८ 'ऊर्जिदृणातेरलचौ पूर्वपदान्तलोपश्च'। 'ऊर्दरः शूररक्षसोः'।७१९ 'कृदरादयश्च'। कृदरः कुसूलः। मृदरं विलसत्। सृदरः सर्पः। ७२० 'हन्तेर्युनाद्यन्तयोर्घत्वतत्वे'। घातनो मारकः। ७२१ 'क्रमिगमिक्षमिभ्यस्तुन्वृद्धिश्च'। क्रान्तुः पक्षी। गान्तुः पथिकः। क्षान्तुर्मशकः। ७२२ 'हर्यतेः कन्यन्हिरच्'। कन्यन्प्रत्ययः। हिरण्यम्। ७२३ 'कृञः पासः'। कर्पासः। बिल्वादित्वात्कार्पासं वस्त्रम्। ७२४ 'जनेस्तु रश्च'। जर्तुर्हस्ती योनिश्च। ७२५ 'ऊर्णोतेर्डः'। ऊर्णा। ७२६ 'दधातेर्यन्नुट् च'। धान्यम्। ७२७ 'जीर्यतेः क्रिन्रश्च वः'। 'जिव्रिः स्यात्कलपक्षिणोः'। बाहुलकात् 'हलि च' (सू ३५४) इति दीर्घो न। ७२८ 'मव्यतेर्यलोपो मश्चापतुट् चालः'। मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य। ममापतालो विषयः। ७२९ 'ऋजेः कीकन्'। ऋजीक इन्द्रो धूमश्च। ७३० 'तनोतेर्डउः सन्वच्च'। 'तितडः पुंसि क्लीबे च'। ७३१ 'अर्भकपृथुकपाका वयसि'। 'ऋधु वृद्धौ'। अतो वुन्। भकारश्चान्तादेशः। प्रथेः कुकन्संप्रसारणं च। पिबतेः कन्। ७३२ 'अवद्यावमाधमार्वरेफाः कुत्सिते'। वदेर्नञि यत्। अवद्यम्। अवतेरमः। वस्य पक्षे धः।अवमः। अधमः। अर्तेर्वन्। अर्वा। रिफतेस्तौदादिकाद्रेफः। ७३३ 'लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः'। तरौ प्रत्ययौ क्रमात्स्तो धातोर्ह्रस्वः प्रत्ययस्य पुट्। लिप्तं श्लिष्टम्। रिप्रं कुत्सितम्। ७३४ 'क्लिशेरीच्चोपधायाः कन्लोपश्च लो नाम्च'। क्लिशेः कन्स्यादुपधाया ईत्वं लस्य लोपो नामागमश्च। कीनाशो यमः। किन्त्वफलं चिन्त्यम्। ७३५ 'अश्नोतेराशुकर्मणि वरट् च'। चकारादुपधाया ईत्वम्। ईश्वरः। ७३६ 'चतेरुरन्'। चत्वारः। ७३७ 'प्रा (प्रेऽ) ततेररन्'। प्रातः। ७३८ 'अमेस्तुट् च'। अन्तर्मध्यम्। ७३९ 'दहेर्गो लोपो दश्च नः'। गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य नकारः। नगः। ७४० 'सिचेः संज्ञायां हनुमौ कश्च'। सिञ्चतेः कप्रत्ययो हकारादेशो नुम्च स्यात्। सिंहः। ७४१ 'व्याङि घ्रातेश्च जातौ'। कप्रत्ययः स्यात्। व्याघ्रः। ७४२ 'हन्तेरच्घुरच्'। घोरम्। ७४३ 'क्षमेरुपधालोपश्च'। चादच्। क्ष्मा। ७४४ 'तरतेर्ड्रिः'। त्रयः। त्रीन्। ७४५ 'ग्रहेरनिः'। ग्रहणिः। ङीष्। ग्रहणी व्याधिभेदः। ७४६ 'प्रथेरमच्'। प्रथमः। ७४७ 'चरेश्च'। चरमः। ७४८ 'मङ्गेरलच्'। मङ्गलम्। इत्युणादिषु पञ्चमः पादः।

३१६९। उणादयो बहुलम्। ३।३।१। एते वर्तमाने संज्ञायां च बहुलं स्युः। केचिदविहिता अप्यूह्याः।

'संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।
कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु' (भाष्यम्)।

३१७०। भूतेऽपि दृश्यन्ते। ३।३।२।

३१७१। भविष्यति गम्यादयः। ३।३।३।

३१७२। दाशगोघ्नौ संप्रदाने। ३।४।७३। एतौ संप्रदाने कारके निपात्येते। दाशन्ति तस्मै दाशः। गां हन्ति तस्मै गोघ्नोऽतिथिः।

३१७३। भीमादयोऽपादाने। ३।४।७४। भीमः। भीष्मः। प्रस्कन्दनः। प्रक्षः। मूर्खः। खलतिः।

३१७४ । ताभ्यामन्यत्रोणादयः । ३ । ४ । ७५ । संप्रदानापादानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ।

३१७५ । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् । ३ । ३ । १० । क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपेण तृजादयो न । पुनर्ण्वुलुक्तेः ।

३१७६ समानकर्तृकेषु तुमुन् । ३ । ३ । १५८ । अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन्स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ।

३१७७ । शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् । ३ । ४ । ६५ । एषूपपदेषु धातोस्तुमुन्स्यात् । शक्नोति भोक्तुम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव संबध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ।

३१७८ । पर्याप्तिवचनेष्वलमर्थेषु । ३ । ४ । ६६ । पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन्स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि । 'पर्याप्तिवचनेषु' किम् । अलं भुक्त्वा । 'अलमर्थेषु' किम् । पर्याप्तं भुङ्क्ते । प्रभूतमेह गम्यते न तु भोक्तुः सामर्थ्यम् ।

३१७९ । कालसमयवेलासु तुमुन् । ३ । ३ । १६७ । पार्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन्स्यात् । कालः समयो वेलानेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते तेनेह न । 'भूतानि कालः पचतीति वार्ता' ।

३१८० । भाववचनाश्च । ३ । ३ । ११ । भाव इत्य... प्रा... वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ।

३१८१ । अण्कर्मणि च । ३ । ३ । १२ । कर्मण्युपपदे क्रियार्थायां क्रियायां चाण्स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन्बाधते । कम्बलदायो व्रजति ।

३१८२ । पदरुजविशस्पृशो घञ् । ३ । ३ । १६ । भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः ।

३१८३ । सृ स्थिरे । ३ । ३ । १७ । 'सृ' इति लुप्तविभक्तिकं सर्तेः स्थिरे कर्तरि घञ्स्यात् । सरति कालान्तरमिति सारः । 'व्याधिमत्स्यबलेषु चेति वाच्यम्' । (वा २१७४) अतिसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्र सरतिः । रुधिरादिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । 'सारो बले दृढांशे च' ।

३१८४ । भावे । ३ । ३ । १८ । सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्स्यात् । पाकः । पाकौ ।

३१८५ । स्फुरतिस्फुलत्योर्घञि । ६ । १ । ४७ । अनयोरेच आत्वं स्याद्घञि । स्फारः । स्फालः । 'उपसर्गस्य घञि–' (सू १०४४) इति दीर्घः । परीहारः । 'इकः काशे' (सू १०४५) । काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । 'इकः' किम् । प्रकाशः । 'नोदात्तोपदेश–' (सू २७६२) इति न वृद्धिः । शमः । आचमादेस्तु आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ।

३१८६। स्यदो जवे। ६। ४। २८। स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते। स्यदो वेगः। अन्यत्र स्यन्दः।

३१८७। अवोदैधौद्मप्रश्रथहिमश्रथाः। ६। ४। २९। अवोदोऽवक्लेदनम्। एध इन्धनम्। ओद्म उन्दनम्। श्रन्थेर्नलोपो वृद्ध्यभावश्च।

३१८८। अकर्तरि च कारके संज्ञायाम्। ३। ३। १९। कर्तृभिन्ने कारके घञ्स्यात्।

३१८९। घञि च भावकरणयोः। ६। ४। २७। रञ्जेर्नलोपः स्यात्। रागः। 'अनयोः' किम्। रज्यत्यस्मिन्रङ्गः। प्रास्यत इति प्रासः। 'संज्ञायाम्' इति प्रायिकम्। को भवता लाभो लब्धः। इत उत्तरं 'भावे' 'अकर्तरि कारके' इति 'कृत्यल्युटो बहुलम्' (सू २८४१) इति यावद्द्वयमप्यनुवर्तते।

३१९०। परिमाणाख्यायां सर्वेभ्यः। ३। ३। २०। घञ् अजपोर्बाधनार्थमिदम्। एकस्तण्डुलनिचायः। द्वौ शूर्पनिष्पावौ। द्वौ कारौ। 'दारजारौ कर्तरि णिलुक्च' (वा २१८२)। दारयन्तीति दाराः। जारयन्तीति जाराः।

३१९१। इङश्च। ३। ३। २१। घञ्। अचोऽपवादः। उपेत्यास्मादधीयते उपाध्यायः। 'अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्' (वा २१८४)। उपाध्याया—उपाध्यायी। 'शॄ वायुवर्णनिवृतेषु' (वा २१८५)। 'शॄ' इत्यविभक्तिको निर्देशः। शारो वायुः। करणे घञ्। शारो वर्णः। चित्रीकरणमिह धात्वर्थः। निव्रियते अव्रियतेऽनेनेति निवृतमावरणम्। बाहुलकात्करणे क्तः। 'गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः'। अकृतप्रावरण इत्यर्थः।

३१९२। उपसर्गे रुवः। ३। ३। २२। घञ्। संरावः। 'उपसर्गे' किम्। रवः।

३१९३। अभिनिसः स्तनः शब्दसंज्ञायाम्। ८। ३। ८६। अस्मात्स्तनः सस्य मूर्धन्यः। अभिनिष्टानो वर्णः। 'शब्दसंज्ञायाम्' किम्। अभिनिःस्तनति मृदङ्गः।

३१९४। समि युद्रुदुवः। ३। ३। २३। संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः। पिष्टविकारोऽपूपविशेषः। संद्रावः। संदावः।

३१९५। श्रिणीभुवोऽनुपसर्गे। ३। ३। २४। श्रायः। नायः। भावः। 'अनुपसर्गे' किम्। प्रश्रयः। प्रणयः। प्रभवः। कथम् 'प्रभावो राज्ञः' इति। प्रकृष्टो भाव इति प्रादिसमासः। कथम् 'राज्ञो नय' इति। बाहुलकात्।

३१९६। वौ क्षुश्रुवः। ३। ३। २५ विक्षावः। विश्रावः। 'वौ' किम्। क्षवः। श्रवः।

३१९७। अवोदोर्नियः। ३। ३। २६। अवनायोऽधो नयनम्। उन्नायः ऊर्ध्वनयनम्। कथम् 'उन्नयः उत्प्रेक्षा' इति। बाहुलकात्।

३१९८। प्रे द्रुस्तुस्रुवः। ३। ३। २७। प्रद्रावः। प्रस्तावः। प्रस्रावः। 'प्रे' इति किम्। द्रवः स्तवः। स्रवः।

३१९९। निरभ्योः पूल्वोः। ३। ३। २८। निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः। अभिलावः। 'निरभ्योः' किम्। पवः। लवः।

३२००। उन्न्योर्ग्रः। ३। ३। २९। उद्गारः। निगारः। 'उन्न्योः' किम्। गरः।

३२०१। कॄ धान्ये। ३।३।३०। 'कॄ' इत्यस्माद्धान्यविषयकादुन्योर्घञ्स्यात्। उत्कारो निकारो धान्यस्य विक्षेप इत्यर्थः। 'धान्ये' किम्। भिक्षोत्करः। पुष्पनिकरः।

३२०२। यज्ञे समि स्तुवः। ३।३।३१। समेत्य स्तुवन्ति यस्मिन्देशे छन्दोगाः स देशः संस्तावः। 'यज्ञे' किम्। संस्तवः परिचयः।

३२०३। प्रे स्त्रोऽयज्ञे। ३।३।३२। 'अयज्ञे' इति छेदः। यज्ञे इति प्रकृतत्वात्। प्रस्तारः। 'अयज्ञे' किम्। बर्हिषः प्रस्तरो मुष्टिविशेषः।

३२०४। प्रथने वावशब्दे। ३।३।३३। विपूर्वात्स्तृणातेर्घञ्स्यादशब्दविषये प्रथने। पटस्य विस्तारः। 'प्रथने' किम्। तृणविस्तरः। 'अशब्दे' किम्। ग्रन्थविस्तरः।

३२०५। छन्दोनाम्नि च। ३।३।३४। 'स्त्र' इत्यनुवर्तते। विष्टारपङ्क्तिश्छन्दः। विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ्। ततः कर्मधारयः।

३२०६। छन्दोनाम्नि च। ८।३।९४। विपूर्वात्स्तृणातेर्घञन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि। इति षत्वम्।

३२०७। उदि ग्रहः। ३।३।३५। उद्ग्राहः।

३२०८। समि मुष्टौ। ३।३।३६। मल्लस्य संग्राहः। 'मुष्टौ' किम्। द्रव्यस्य संग्रहः।

३२०९। परिन्योर्नीणोर्द्यूताभ्रेषयोः। ३।३।३७। परिपूर्वान्नयतेर्निपूर्वादिणश्च घञ्स्यात्क्रमेण द्यूतेऽभ्रेषे च विषये। परिणायेन शारान्हन्ति। समन्तान्नयनेनेत्यर्थः। एषोऽत्र न्यायः। उचितमित्यर्थः। 'द्यूताभ्रेषयोः' किम्। परिणयो विवाहः। न्ययो नाशः।

३२१०। परावनुपात्यय इणः। ३।३।३८। क्रमप्राप्तस्यानतिपातोऽनुपात्ययः। तव पर्यायः। 'अनुपात्यये' किम्। कालस्य पर्ययः। अतिपात इत्यर्थः।

३२११। व्युपयोः शेतेः पर्याये। ३।३।३९। तव विशायः। तव राजोपशायः। 'पर्याये' किम्। विशयः संशयः। उपशयः समीपशयनम्।

३२१२। हस्तादाने चेरस्तेये। ३।३।४०। हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते। पुष्पप्रचायः। 'हस्तादाने' किम्। वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति। 'अस्तेये' किम्। पुष्पप्रचयश्चौर्येण।

३२१३। निवासचितिशरीरोपसमाधानेष्वादेश्च कः। ३।३।४१। एषु चिनोतेर्घञादेश्च ककारः। उपसमाधानं राशीकरणं तच्च धात्वर्थः। अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः। निवासे। काशीनिकायः। चितौ। आकायमग्निं चिन्वीत। शरीरे। चीयतेऽस्मिन्नस्थ्यादिकमिति कायः। समूहे। गोमयनिकायः। 'एषु' किम्। चयः। 'चः कः' इति वक्तव्ये आदेरित्युक्तेर्यङ्लुक्यादेरेव यथा स्यादिति। गोमयानां निकेचायः। पुनः पुना राशीकरणमित्यर्थः।

३२१४। संघे चानौत्तराधर्ये। ३।३।४२। चेर्घञादेश्च कः। भिक्षुनिकायः। प्राणिनां समूहः संघः। 'अनौत्तराधर्ये' किम्। सूकरनिचयः। संघे किम्। ज्ञानकर्मसमुच्चयः।

३२१५। कर्मव्यतिहारे णच्स्त्रियाम्। ३।३।४३। स्त्रीलिङ्गे भावे णच्।

३२१६। णचः स्त्रियामञ्। ५।४।१४।

३२१७। न कर्मव्यतिहारे। ७। ३। ६। अत्र ऐज्न स्यात्। व्यावक्रोशी। व्यावहासी।

३२१८। अभिविधौ भाव इनुण्। ३। ३। ४४।,

३२१९। अणिनुणः। ५। ४। १५। 'इनण्यनपत्ये' (सू १२४९)। साराविणं वर्तते।

३२२०। आक्रोशेऽवन्योर्ग्रहः। ३। ३। ४५। 'अव' 'नि' एतयोर्ग्रहेर्घञ्स्यात् शापे। अवग्राहस्ते भूयात्। अभिभव इत्यर्थः। निग्राहस्ते भूयात्। बाध इत्यर्थः। 'आक्रोशे' किम्। अवग्रहः पदस्य। निग्रहश्चोरस्य।

३२२१। प्रे लिप्सायाम्। ३। ३। ४६। पात्रप्रग्राहेण चरति भिक्षुः।

३२२२। परौ यज्ञे। ३। ३। ४७। उत्तरः परिग्राहः। स्फ्येन वेदेः स्वीकरणम्।

३२२३। नौ वृ धान्ये। ३। ३। ४८। 'वृ' इति लुप्तपञ्चमीकम्। नीवाराः। 'धान्ये' किम्। निवरा कन्या। क्विन्विषयेऽपि बाहुलकादप्। प्रवरा सेतिवत्।

३२२४। उदि श्रयतियौतिपूद्रुवः। ३। ३। ४९। उच्छ्रायः। उद्यावः। उत्पावः। उद्द्रावः। कथं 'पतनान्ताः समुच्छ्रयाः' इति। बाहुलकात्।

३२२५। विभाषाङि रुप्लुवोः। ३। ३। ५०। आरावः-आरवः। आप्लावः-आप्लवः।

३२२६। अवे ग्रहो वर्षप्रतिबन्धे। ३। ३। ५१। विभाषेति वर्तते। अवग्रहः-अवग्राहः। 'वर्षप्रतिबन्धे' किम्। अवग्रहः पदस्य।

३२२७। प्रे वणिजाम्। ३। ३। ५२। प्रे ग्रहेर्घञ्वा वणिजां संबन्धी चेत्प्रत्ययार्थः। तुलासूत्रमिति यावत्। तुलाप्रग्राहेण चरति। तुलाप्रग्रहेण।

३२२८। रश्मौ च ३। ३। ५३। प्रग्रहः-प्रग्राहः।

३२२९। वृणोतेराच्छादने। ३। ३। ५४। विभाषा प्र इत्येव। प्रवारः-प्रवरः।

३२३०। परौ भुवोऽवज्ञाने। ३। ३। ५५। परिभावः-परिभवः। 'अवज्ञाने' किम्। सर्वतो भवनं परिभवः।

३२३१। एरच्। ३। ३। ५६। चयः। जयः। 'भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्यर्थम्' (वा २१९७-९८)। भयम्। वर्षम्।

३२३२। ऋदोरप्। ३। ३। ५७। ऋवर्णान्तादुवर्णान्तादप्। करः। गरः। शरः। यवः। लवः। स्तवः। पवः।

३२३३। वृक्षासनयोर्विष्टरः। ८। ३। ९३। अनयोर्विपूर्वस्य स्तृञः षत्वं निपात्यते। विष्टरो वृक्ष आसनं च। 'वृक्ष-' इति किम्। वाक्यस्य विस्तरः।

३२३४। ग्रहवृदृनिश्चिगमश्च। ३। ३। ५८। अप्स्यात्। घञचोरपवादः। ग्रहः। वरः। दरः। निश्चयः। गमः। 'वशिरण्योरुपसंख्यानम्' (वा २२०३)। वशः। रणः। 'घञर्थे कविधानम्' (वा २२०४)। प्रस्थः। विघ्नः। 'द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम्' (वा ३४२९)। चक्रम्। चिक्लिदम्। चक्नसः।

३२३५। उपसर्गेऽदः। ३। ३। ५९। अप्स्यात्।

३२३६। घञपोश्च। २। ४। ३८। अदेर्घस्लृ स्याद्घञ्यपि च। प्रघसः। विघसः। 'उपसर्गे' किम्। घासः।

३२३७। नौ ण च। ३। ३। ६०। नौ उपपदे अदेर्णः स्यादप्च। न्यादः। निघसः।

३२३८। व्यधजपोरनुपसर्गे। ३। ३। ६१। अप्स्यात्। व्यधः। जपः। उपसर्गे तु। आव्याधः। उपजापः।

३२३९। स्वनहसोर्वा। ३। ३। ६२। अप्। पक्षे घञ्। स्वनः-स्वानः। हसः-हासः। अनुपसर्ग इत्येव। प्रस्वानः। प्रहासः।

३२४०। यमः समुपनिविषु च। ३। ३। ६३। एष्वनुपसर्गे च यमेरब्वा। संयमः-संयामः। उपयमः-उपयामः। नियमः-नियामः। वियमः-वियामः। यमः-यामः।

३२४१। नौ गदनदपठस्वनः। ३। ३। ६४। अब्वा स्यात्। निगदः-निगादः। निनदः-निनादः। निपठः-निपाठः। निस्वनः-निस्वानः।

३२४२। क्वणो वीणायां च। ३। ३। ६५। नावनुपसर्गे च वीणाविषयाच्च क्वणतेरब्वा स्यात्। वीणाग्रहणं प्राद्यर्थम्। निक्वणः-निक्वाणः। क्वणः-क्वाणः। वीणायां तु। प्रक्वणः-प्रक्वाणः।

३२४३। नित्यं पणः परिमाणे। ३। ३। ६६। अप्स्यात्। मूलकपणः। शाकपणः। व्यवहारार्थं मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः। 'परिमाणे' किम्। पाणः।

३२४४। मदोऽनुपसर्गे। ३। ३। ६७। धनमदः। उपसर्गे तु। उन्मादः।

३२४५। प्रमदसंमदौ हर्षे। ३। ३। ६८। 'हर्षे' किम्। प्रमादः। संमादः।

३२४६। समुदोरजः पशुषु। ३। ३। ६९। संपूर्वोऽजिः समुदाय उत्पूर्वश्च प्रेरणे तस्मात्पशुविषयकादप्स्यात्। 'अघञपोः' इत्युक्तेर्वीभावो न। समजः पशूनां संघः। उदजः पशूनां प्रेरणम्। 'पशुषु' किम्। समाजो ब्राह्मणानाम्। उदाजः क्षत्रियाणाम्।

३२४७। अक्षेषु ग्लहः। ३। ३। ७०। अक्षशब्देन देवनं लक्ष्यते तत्र यत्पणरूपेण ग्राह्यं तत्र 'ग्लहः' इति निपात्यते। अक्षस्य ग्लहः। 'ग्यात्युक्षीमभिसरणग्लहामदीव्यन्'। 'अक्षेषु' किम्। पादस्य ग्रहः।

३२४८। प्रजने सर्तेः। ३। ३। ७१। प्रजनं प्रथमगर्भग्रहणम्। गवामुपसरः। कथम् 'अवसरः' 'प्रसरः' इति। अधिकरणे 'पुंसि संज्ञायाम्-' (सू ३२९६) इति घः।

३२४९। ह्वः संप्रसारणं च न्यभ्युपविषु। ३। ३। ७२। निहवः। अभिहवः। उपहवः। विहवः। 'एषु' किम्। प्रह्वायः।

३२५०। आङि युद्धे। ३। ३। ७३। आहूयन्तेऽस्मिन्नित्याहवः। 'युद्धे' किम्। आह्वायः।

३२५१। निपानमाहावः। ३। ३। ७४। आङ्पूर्वस्य ह्वयतेः संप्रसारणमब्वृद्धिश्चो-दकाधारश्चेद्वाच्यः। 'आहावस्तु निपानं स्यादुपकूपजलाशये'।

३२५२। भावेऽनुपसर्गस्य। ३। ३। ७५। अनुपसर्गस्य ह्वयतेः संप्रसारणमप्च स्याद्भावे। हवः।

३२५३। हनश्च वधः। ३। ३। ७६। अनुपसर्गाद्धन्तेर्भावे अप्स्यात्। वधादेशश्चान्तो-दात्तः। 'वधेन दस्युम्'। चाद्धञ्। घातः।

३२५४। मूर्तौ घनः। ३। ३। ७७। मूर्तिः काठिन्यं तस्मिन्नभिधेये हन्तेरप्स्यात्। घनश्चादेशः। अभ्रघनः। कथम् 'सैन्धवघनमानय' इति। धर्मशब्देन धर्मी लक्ष्यते।

३२५५ । अन्तर्घनो देशे । ३ । ३ । ७८ । वाहीकग्रामविशेषस्य संज्ञेयम् । 'अन्तर्घणः' इति पाठान्तरम् ।

३२५६ । अगारैकदेशे प्रघणः प्रघाणश्च । ३ । ३ । ७९ द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः-प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ।

३२५७ । उद्घनोऽत्याधानम् । ३ । ३ । ८० । अत्याधानमुपरिस्थापनम् । यस्मिन्काष्ठेऽन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्घनः । अधिकरणेऽप् ।

३२५८ । अपघनोऽङ्गम् । ३ । ३ । ८१ । अङ्गं शरीरावयवः । स चेह न सर्वः किं तु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ।

३२५९ । करणेऽयोविद्रुषु । ३ । ३ । ८२ । एषु हन्तेः करणेऽप्स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । 'द्रुघणः' इत्येके । 'पूर्वपदात्संज्ञायाम्-' (सू ८५७) इति णत्वम् । संज्ञैषा कुठारस्य । द्रुर्वृक्षः ।

३२६० । स्तम्बे क च । ३ । ३ । ८३ । स्तम्ब उपपदे हन्तेः करणे कः स्यादप्च । पक्षे घनादेशश्च । स्तम्बघ्नः-स्तम्बघनः । करण इत्येव । स्तम्बघातः ।

३२६१ । परौ घः । ३ । ३ । ८४ । परौ हन्तेरप्स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ।

३२६२ । परेश्च घाङ्कयोः । ८ । २ । २२ । परे रेफस्य लो वा स्याद्घशब्देऽङ्कशब्दे च । पलिघः-परिघः । पर्यङ्कः-पल्यङ्कः । इह 'तरतमपौ घः' (सू २००३) इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ।

३२६३ । उपघ्न आश्रये । ३ । ३ । ८५ । उपपूर्वाद्धन्तेरप्स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यत इति पर्वतोपघ्नः ।

३२६४ । संघोद्घौ गणप्रशंसयोः । ३ । ३ । ८६ । संहननं संघः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायत इत्युद्घः । कर्मण्यप् । गत्यर्थानां बुद्ध्यर्थत्वाद्धन्तिर्ज्ञाने ।

३२६५ । निघो निमितम् । ३ । ३ । ८७ । समन्तान्मितं निमितम् । निर्विशेषं हन्यन्ते ज्ञायन्ते इति निघाः वृक्षाः । समारोहपरिणाहाः इत्यर्थः ।

३२६६ । ड्वितः क्त्रिः । ३ । ३ । ८८ । अयं भाव एव स्वभावात् । 'क्त्रेर्मन्नित्यम्' । (सू १९७०) नित्यग्रहणात्क्त्रिमब्विषयः । अत एव त्र्यन्तेन न विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् । उप्त्रिमम् ।

३२६७ । ट्वितोऽथुच् । ३ । ३ । ८९ । अयमपि स्वाभावाद्भाव एव । ट्वेपृ । वेपथुः । श्वयथुः ।

३२६८ । यजयाचयतविच्छप्रच्छरक्षो नङ् । ३ । ३ । ९० । यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । 'प्रश्ने चासन्न-' (सू २७७७) इति ज्ञापकान्न संप्रसारणम् । ङित्त्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ।

३२६९ । स्वपो नन् । ३ । ३ । ९१ । स्वप्नः ।

३२७० । उपसर्गे घोः किः । ३ । ३ । ९२ । प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः

३२७१ । कर्मण्यधिकरणे च । ३ । ३ । ९३ । कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ।

३२७२ । स्त्रियां क्तिन् । ३ । ३ । ९४ । स्त्रीलिङ्गे भावादौ क्तिन्स्याद्घञोऽपवादः । अजपौ तु परत्वाद्बाधेते । कृतिः । चितिः । स्तुतिः । स्फायी—स्फातिः । 'स्फीतिकामः' इति तु प्रामादिकम् । क्रान्ताद्वात्वर्थे णिचि 'अच इः' इति वा समाधेयम् । 'श्रुयजीषिस्तुभ्यः करणे' (वा २२११) । श्रूयतेऽनया श्रुतिः । यजेरिषेश्च इष्टिः । स्तुतिः । 'ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः' (वा ४८२६) । तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । 'ह्लादः—' (सू ३०७३) इति योगविभागात्क्तिनि ह्रस्वः । प्रह्लत्तिः । 'ति च' (सू ३०३७) । चूर्तिः । फुल्तिः । 'चायतेः क्तिनि चिभावो वाच्यः' (वा ४४१८) । अपचितिः । 'संपदादिभ्यः क्विप्' (वा २२३३) । संपत् । विपत् । 'क्तिन्नपीष्यते' । संपत्तिः । विपत्तिः ।

३२७३ । स्थागापापचो भावे । ३ । ३ । ९५ । क्तिन्स्यादङोऽपवादः । प्रस्थितिः । उपस्थितिः । संगीतिः । संपीतिः । पक्तिः । कथम् 'अवस्था' 'संस्था' इति । 'व्यवस्थायाम्' इति ज्ञापकात् ।

३२७४ । ऊतियूतिजूतिसातिहेतिकीर्तयश्च । ३ । ३ । ९७ । अवतेः 'ज्वरत्वर—' (सू २६५४)इत्यूठ् । ऊतिः । स्वरार्थं वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । 'द्यतिस्यतिमास्था—' (सू ३०७४) इतीत्वे प्राप्त इत्वाभावो निपात्यते । सनोतेर्वा 'जनसन—' (सू २५०४) इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तिः ।

३२७५ । व्रजयजोर्भावे क्यप् । ३ । ३ । ९८ । व्रज्या । इज्या ।

३२७६ । संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः । ३ । ३ । ९९ । समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः संज्ञायाम् । 'अजेः क्यपि वीभावो नेति वाच्यम्' (वा १५९६) । समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या । आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्याभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ।

३२७७ । कृञः । श च । ३ । ३ । १०० । 'कृञः' इति योगविभागः । कृञः क्यप्स्यात् । कृत्या । 'श च' । चात्क्तिन् । क्रिया । कृतिः ।

३२७८ । इच्छा । ३ । ३ । १०१ । इषेर्भावे शो यगभावश्च निपात्यते । इच्छा । 'परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्' (वा २२१५) । शो यक्च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । मृग अन्वेषणे चुरादावदन्तः । अतो लोपाभावोऽपि । शे यकि णिलोपः । मृगया । अटतेः शे यकि टचशब्दस्य द्वित्वं पूर्वभागे यकारानिवृत्तिर्दीर्घश्च । अटाट्या । 'जागर्तेरकारो वा' (वा २२१६) । पक्षे शः जागरा—जागर्या ।

३२७९ । अ प्रत्ययात् । ३ । ३ । १०२ । प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ।

३२८० । गुरोश्च हलः । ३ । ३ । १०३ । गुरुमतो हलन्तात्स्त्रियामकारः स्यात् ।

ईहा। ऊहा। 'गुरोः' किम्। भक्तिः। 'हलः' किम्। नीतिः। 'निष्ठायां सेट इति वक्तव्यम्' (वा २२०८) नेह। आप्तिः। 'तितुत्र–' (सू ३१६३) इति नेट्। दीप्तिः। 'तितुत्रेष्वग्रहादीनामिति वाच्यम्' (वा ४३९३)। निगृहीतिः। निपठितिः।

३२८१। षिद्भिदादिभ्योऽङ्। ३। ३। १०४। षित्भ्यो भिदादिभ्यश्च स्त्रियामङ्। जॄष्। 'ऋदृशोऽङि गुणः' (सू २४०६)। जरा। त्रपूष्। त्रपा। भिदा। विदारण एवायम्। भित्तिरन्या। छिदा। मृजा। 'कृपेः संप्रसारणं च' (गण ३२)। कृपा।

३२८२। चिन्तिपूजिकथिकुम्बिचर्चश्च। ३। ३। १०५। अङ् स्यात्। युचोऽपवादः। चिन्ता। पूजा। कथा। कुम्बा। चर्चा।

३२८३। आतश्चोपसर्गे। ३। ३। १०६। अङ् स्यात्। क्तिनोऽपवादः। प्रदा। उपदा। 'श्रदन्तरोरुपसर्गवद्वृत्तिः' (वा ११३२-११४७)। श्रद्धा। अन्तर्धा। 'उपसर्गे घोः किः' (सू ३२७०) इत्यनेन किः। अन्तर्धिः।

३२८४। ण्यासश्रन्थो युच्। ३। ३। १०७। अकारस्यापवादः। कारणा। हारणा। आसना। श्रन्थना। 'घट्टिवन्दिविदिभ्यश्चेति वाच्यम्' (वा २२२२)। घट्टना। वन्दना। वेदना। 'इषेरनिच्छार्थस्य' (वा २२२३)। अन्वेषणा। 'परेर्वा' (वा २२२४)। पर्येषणा परीष्टिः।

३२८५। रोगाख्यायां ण्वुल्बहुलम्। ३। ३। १०८। प्रच्छर्दिका। प्रवाहिका। विचर्चिका। क्वचिन्न। शिरोऽर्तिः। 'धात्वर्थनिर्देशे ण्वुल्वक्तव्यः' (वा २२२५)। आसिका। शायिका। 'इक्श्तिपौ धातुनिर्देशे' (वा २२२६)। पचिः-पचतिः। 'वर्णात्कारः' (वा २२२७)। निर्देश इत्येव। अकारः। ककारः। 'रादिफः' (वा २२२८)। रेफः। 'मत्वर्थाच्छः' (वा २२२९)। बहुलवचनादकारलोपः। मत्वर्थीयः। 'इणजादिभ्यः' (वा २२३०)। आजिः। आतिः। 'इञ्वपादिभ्यः' (वा २२३१)। वापिः। वासिः। स्वरे भेदः। 'इक्कृष्यादिभ्यः' (वा २२३२)। कृषिः। गिरिः।

३२८६। संज्ञायाम्। ३। ३। १०९। अत्र धातोर्ण्वुल्। उद्दालकपुष्पभञ्जिका।

३२८७। विभाषाख्यानपरिप्रश्नयोरिञ्च। ३। ३। ११०। परिप्रश्न आख्याने च गम्य इञ्स्यात्। चाण्ण्वुल्। विभाषोक्तेर्यथाप्राप्तमन्येऽपि कां त्वं कारिं–कारिकां क्रियां–कृत्यां–कृतिं वाकार्षीः। सर्वां कारिं–कारिकां–क्रियां–कृत्यां–कृतिं–वाकार्षम्। एवं गाणिं–गणिकां–गणनाम्। पाचिं–पाचिकां–पचां–पक्तिम्।

३२८८। पर्यायार्हर्णोत्पत्तिषु ण्वुच्। ३। ३। १११। पर्यायः परिपाटीक्रमः। अर्हणमर्हः योग्यता। पर्यायादिषु द्योत्येषु ण्वुच्वा स्यात्। भवत आसिका। शायिका। अग्रगामिका। भवानिक्षुभक्षिकामर्हति। ऋणे। इक्षुभक्षिकां मे धारयति। उत्पत्तौ। इक्षुभक्षिका उदपादि।

३२८९। आक्रोशे नञ्यनिः। ३। ३। ११२। विभाषेति निवृत्तम्। नञ्युपपदेऽनिः स्यादाक्रोशे। अजीवनिस्ते शठ भूयात्। अप्रयाणिः। 'कृत्यल्युटो बहुलम्' (सू २८४१) भावेऽकर्तरि च कारके संज्ञायामिति च निवृत्तम्। राज्ञा भुज्यन्ते राजभोजनाः शालयः। 'नपुंसके भावे क्तः' (सू ३०९०)।

३२९०। ल्युट् च। ३। ३। ११५। हसितम्। हसनम्। योगविभाग उत्तरार्थः।

३२९१ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् । ३ । ३ । ११६ । येन स्पृश्यमानस्यकर्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । 'कर्तुः' इति किम् । गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता, किं तु कर्म ।

३२९२ । वा यौ । २ । ४ । ५७ । अजेर्वी वा स्याद्यौ । प्रवयणम् । प्राजनम् ।

३२९३ । करणाधिकरणयोश्च । ३ । ३ । ११७ । ल्युट् स्यात् । इध्मप्रव्रश्चनः कुठारः । गोदोहनी स्थाली । [illegible]

३२९४ । अन्त[illegible]
देशे तु अन्तर्हनने [illegible]

३२९५ । अ[illegible]
अदेश इत्येव । अन्त[illegible]

३२९६ । पुंसि संज्ञा[illegible]

३२९७ । छादेर्घेऽद्व[illegible]
द्वे परे । दन्ताश्छाद्यन्ते [illegible]

३२९८ । गोचरस[illegible]
न्ते । 'हलश्च' (सू ३[illegible]
देशः । संचरन्तेऽ[illegible]
निपातनाद्धीभावो [illegible]
निकषः ।

३२९९ । [illegible]

३३०० । [illegible]
न्निति रामः । [illegible]

३३०१ । [illegible]
यन्त्युत्सुवन्ति [illegible]

३३०२ । [illegible]
च्यत उद्ध्रियते [illegible]

३३०३ । [illegible]
'आलम्' इति [illegible]

३३०४ । [illegible]
तोऽप्ययमिति [illegible]
(वा २२३८) [illegible]

३३०५ । ई[illegible]
निवृत्तम् । एषु दु[illegible]
च । कृच्छ्रे । दुष्क[illegible]
नेति वाच्यम्' ([illegible]

३३०६। उपसर्गात्खल्घञोः । ७ । १ । ६७ । उपसर्गादेव लभेर्नुम्स्यात् । ईषत्प्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः उपालम्भः । 'उपसर्गात्' किम् । ईषल्लभः । लाभः ।

३३०७। न सुदुर्भ्यां केवलाभ्याम् । ७ । १ । ६८ । उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुम स्यात्खल्घञोः । सुलभम् । दुर्लभम् । 'केवलाभ्याम्' किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ।

३३०८। कर्तृकर्मणोश्च भूकृञोः । ३ । ३ । १२७ । कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञोः खल्स्यात् । 'यथासंख्यं नेष्यते' । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये ईषदादयस्तु ततः प्राक् । 'कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम्' (वा २२५१) । खित्त्वान्मुम् । अनाढ्येन दुःखेन भूयते दुराढ्यंभवम् । ईषदाढ्यंभवम् । स्वाढ्यंभवम् । ईषदाढ्यंकरः । दुराढ्यंकरः । स्वाढ्यंकरः । 'च्व्यर्थयोः' किम् । आढ्येन सुभूयते ।

३३०९। आतो युच् । ३ । ३ । १२८ । खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । 'भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः' (वा २२५३) । दुःशासनः । दुर्योधन इत्यादि ।

३३१०। षात्पदान्तात् । ८ । ४ । ३५ । नस्य णो न । निष्पानम् । सर्पिष्पानम् । 'षात्' किम् । निर्णयः । 'पदान्तात्' किम् । पुष्णाति । पदेऽन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ।

३३११ । आवश्यकाधमर्ण्ययोर्णिनिः । ३ । ३ । १७० । अवश्यंकारी । शतंदायी ।

३३१२ । कृत्याश्च ३ । ३ । १७१ । आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ।

३३१३ । क्तिच्क्तौ च संज्ञायाम् । ३ । ३ । १७४ । धातोः क्तिच्क्तश्च स्यादाशिषि संज्ञायाम् । 'तितुत्र-' (सू ३१६३) इति नेट् । भवताद्भूतिः ।

३३१४ । न क्तिचि दीर्घश्च । ६ । ४ । ३९ । अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ।

३३१५ । सनः क्तिचि लोपश्चास्यान्यतरस्याम् । ६ । ४ । ४५ । सनोतेः क्तिच्यात्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ।

३३१६ । अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा । ३ । ४ । १८ । प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । 'अमैवाव्ययेन' (सू ७८३) इति नियमान्नोपपदसमासः । 'दो दद्घोः' (सू ३०७७) अलं दत्त्वा । 'घुमास्था-' (सू २४६२) । पीत्वा खलु । 'अलंखल्वोः' किम् । मा कार्षीत् । 'प्रतिषेधयोः' किम् । अलंकारः ।

३३१७ । उदीचां माङो व्यतीहारे । ३ । ४ । १९ । व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ।

३३१८ । मयतेरिदन्यतरस्याम् । ६ । ४ । ७० । मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचांग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ।

३३१९ । परावरयोगे च । ३ । ४ । २० । परेण पूर्वस्यावरेण परस्य योगे गम्ये

धातोः क्त्वा स्यात्। अप्राप्य नदीं पर्वतः। परनदीयोगोऽत्र पर्वतस्य। अतिक्रम्य पर्वतं स्थिता नदी। अवरपर्वतयोगोऽत्र नद्याः।

३३२०। समानकर्तृकयोः पूर्वकाले। ३। ४। २१। समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। स्नात्वा भुक्त्वा पीत्वा व्रजति। 'अनुदात्त–'(सू २४२८) इत्यनुनासिकलोपः। विष्णुं नत्वा स्तौति। स्वरत्यादेः 'श्र्युकः किति' (सू २३८१) इति नित्यमिडभावः पूर्वविप्रतिषेधेन। स्वृत्वा। सूत्वा। धूत्वा।

३३२१। क्त्वि स्कन्दिस्यन्दोः। ६। ४। ३१। एतयोर्नलोपो न स्यात्क्त्वि परे स्कन्त्वा। ऊदित्त्वादिड्वा। स्यन्त्वा–स्यन्दित्वा।

३३२२। न क्त्वा सेट्। १। २। १८। सेट् क्त्वा किन्न स्यात्। शयित्वा। 'सेट्' किम्। कृत्वा।

३३२३। मृडमृदगुधकुषक्लिशवदवसः क्त्वा। १। २। ७। एभ्यः सेट् क्त्वा कित्। मृडित्वा। 'क्लिशः क्त्वा–' (सू ३०४९) इति वेट्। क्लिशित्वा–क्लिष्ट्वा। उदित्वा। उषित्वा। 'रुदविद–' (सू२६०९) इति कित्त्वम्। रुदित्वा। विदित्वा। मुषित्वा। गृहीत्वा।

३३२४। नोपधात्थफान्ताद्वा। १। २। २३। सेट् क्त्वा कित्स्याद्वा। श्रथित्वा–श्रन्थित्वा। गुफित्वा–गुम्फित्वा। 'नोपधात्' किम्। कोथित्वा। रेफित्वा।

३३२५। वञ्चिलुञ्च्यृतश्च। १। २। २४। सेट् क्त्वा किद्वा। वचित्वा–वञ्चित्वा। लुचित्वा–लुञ्चित्वा। ऋतित्वा–अर्तित्वा।

३३२६। तृषिमृषिकृशेः काश्यपस्य। १। २। २५। एभ्यः सेट् क्त्वा किद्वा। तृषित्वा–तर्षित्वा। मृषित्वा–मर्षित्वा। कृशित्वा–कर्शित्वा। 'रलो व्युपधात्–' (सू २६१७)इति वा कित्त्वम्। द्युतित्वा–द्योतित्वा। लिखित्वा–लेखित्वा। 'रलः' किम्। सेवित्वा। 'व्युपधात्' किम्। वर्तित्वा। 'हलादेः' किम्। एषित्वा। 'सेट्' किम्। भुक्त्वा। 'वसतिक्षुधोरिट्' (सू ३०४६) उषित्वा। क्षुधित्वा–क्षोधित्वा। 'अञ्चेः पूजायम्' (सू ३०४७) इति नित्यमिट्। अञ्चित्वा। गतौ तु। अक्त्वेत्यपि। लुभित्वा–लोभित्वा। 'लुभो विमोहने' (सू ३०४८) इतीट्। विमोहने तु लुब्ध्वा।

३३२७। जॄव्रश्च्योः क्त्वि। ७। २। ५५। आभ्यां परस्य क्त्व इट् स्यात् जरीत्वा–जरित्वा। व्रश्चित्वा।

३३२८। उदितो वा। ७। २। ५६। उदितः परस्य क्त्व इड्वा। शमित्वा। 'अनुनासिकस्य क्वि–' (सू २६६६) इति दीर्घः। शान्त्वा। द्यूत्वा–दवित्वा।

३३२९। क्रमश्च क्त्वि। ६। ४। १८। क्रम उपधाया वा दीर्घः स्यात्। झलादौ क्त्वि परे क्रान्त्वा–क्रन्त्वा। 'झलि' किम्। क्रमित्वा। 'पूङश्च' (सू ३०५०) ति वेट्। पवित्वा–पूत्वा।

३३३०। जान्तनशांविभाषा। ६। ४। ३२। जान्तानां नशेश्च नलोपो वा स्यात्क्त्वि परे। भक्त्वा–भङ्क्त्वा। रक्त्वा–रङ्क्त्वा। 'मस्जिनशोः–' (सू २५१७) इति नुम्। नस्य पक्षे लोपः। नंष्ट्वा नष्ट्वा। 'रधादिभ्यश्च' (सू २५१४) इतीट्पक्षे। नशित्वा। 'झला-

दाविति वाच्यम्'[1] (वा ५०६६)। नेह। अञ्जित्वा। ऊदित्त्वाद्वेट्। पक्षे। अक्त्वा–अङ्क्त्वा। 'जनसन–' (सू २५०४) इत्यात्त्वम्। खात्वा–खनित्वा। 'द्यतिस्यति–' (सू३०७४) इतीत्त्वम्। दित्वा। सित्वा। मित्वा स्थित्वा। 'दधातेर्हिः' (सू३०७६)। हित्वा।

३३३१। जहातेश्च क्त्वि। ७।४।८३। हित्वा। हाङस्तु। हात्वा। 'अदो जग्धिः–' (सू३०८०)। जग्ध्वा।

३३३२। समासेऽनञ्पूर्वे क्त्वो ल्यप्। ७।१।३७। अव्ययपूर्वपदेऽनञ्समासे क्त्वा ल्यबादेशः स्यात्। तुक्। प्रकृत्य। 'अनञ्' किम्। अकृत्वा। पर्युदासाश्रयणान्नेह। परमकृत्वा।

३३३३ षत्वतुकोरसिद्धः। ६।१।८६। षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात्। इति षत्वं न। अधीत्य। प्रेत्य। 'ह्रस्वस्य–' (सू २८५८) इति तुक्।

३३३४। वा ल्यपि। ६।४।३८। अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि। व्यवस्थितविभाषेयम्। तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम्। आगत्य–आगम्य। प्रणत्य–प्रणम्य। प्रहत्य। प्रमत्य। प्रवत्य। वितत्य। 'अदो जग्धिः–' (सू ३०८०)। 'अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते'। (गण) जग्धिविधौ ल्यब्ग्रहणात्। तेन हित्वदत्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न। विधाय। प्रदाय। प्रखन्य। प्रस्थाय। प्रक्रम्य। आपृच्छ्य। प्रदीव्य।

३३३५। न ल्यपि। ६।४।६९। ल्यपि परे घुमास्थादेरीत्त्वं न। धेट्। प्रधाय। प्रमाय। प्रगाय। प्रपाय। प्रहाय। प्रसाय। 'मीनातिमिनोति–' (सू २५०८) इत्यात्त्वम्। प्रमाय। निमाय। उपदाय। 'विभाषा लीयतेः' (सू २५०९) विलाय–विलीय। णिलोपः। उत्तार्य। विचार्य।

३३३६। ल्यपि लघुपूर्वात्। ६।४।५६। लघुपूर्वात्परस्य णेरयादेशः स्याल्ल्यपि। विगणय्य। प्रणमय्य। प्रबेभिदय्य। 'लघुपूर्वात्' किम्। संप्रधार्य।

३३३७। विभाषापः। ६।४।५७। आप्नोतेर्णेरयादेशो वा स्याल्ल्यपि। प्रापय्य–प्राप्य।

३३३८। क्षियः। ६।४।५९। क्षियो ल्यपि दीर्घः स्यात्। प्रक्षीय।

३३३९। ल्यपि च। ६।१।४१। वेञो ल्यपि संप्रसारणं न स्यात्। प्रवाय।

३३४०। ज्यश्च। ६।१।४२। प्रज्याय।

३३४१ व्यश्च। ६।१।४३। उपव्याय।

३३४२। विभाषा परेः। ६।१।४४। परेर्व्येञो वा संप्रसारणं स्याल्ल्यपि। तुकं बाधित्वा परत्वात् 'हलः' (सू २५५९) इति दीर्घः। परिवीय–परिव्याय। कथम् 'मुखं व्यादाय स्वपिति' 'नेत्रे निमील्य हसति' इति। व्यादानसंमीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति।

३३४३। आभीक्ष्ण्ये णमुल्च। ३।४।२२। पौनःपुन्ये द्योत्ये पूर्वविषये णमुल्स्यात् क्त्वा च। द्वित्वम्। स्मारंस्मारं नमति शिवम्। स्मृत्वास्मृत्वा। पायंपायम्। भोजंभोजम्। श्रावंश्रावम्। 'चिण्णमुलोः–' (सू २७६२) इति णमुल्परे णौ वा दीर्घः। गामंगामम्

१ दीक्षिताङ्गीकृतमेतत्। अन्येषां तु युक्तिसिद्धम्।

गमंगमम्। 'विभाषा चिण्णमुलोः' (सू २७६९) इति नुम्वा। लम्भंलम्भम्—लाभंलाभम्। व्यवस्थितविभाषयोपसृष्टस्य नित्यं नुम्। प्रलम्भंप्रलम्भम्। 'जाग्रोऽविचिण्ण—' (सू २४८०) इति गुणः। जागरंजागरम्। ण्यन्तस्याप्येवम्।

३३४४। न यद्यनाकाङ्क्षे। ३। ४। २३। यच्छब्द उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत्। यदयं भुङ्क्ते ततः पठति। इह क्त्वाणमुलौ न। 'अनाकाङ्क्षे' किम्। यदयं भुक्त्वा व्रजति ततोऽधीते।

३३४५। विभाषाग्रेप्रथमपूर्वेषु। ३। ४। २४। आभीक्ष्ण्य इति नानुवर्तते। एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ वा स्तः। अग्रे भोजं व्रजति। अग्रे भुक्त्वा। प्रथमं भोजम्—प्रथमं भुक्त्वा। पूर्वं भोजम्—पूर्वं भुक्त्वा। पक्षे लङादयः। अग्रे भुङ्क्ते ततो व्रजति। आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः। अग्रे भोजंभोजं व्रजति। भुक्त्वाभुक्त्वा।

३३४६। कर्मण्याक्रोशे कृञः खमुञ्। ३। ४। २५। कर्मण्युपपद आक्रोशे गम्ये। चोरंकारमाक्रोशति। करोतिरुच्चारणे। चोरशब्दमुच्चार्येत्यर्थः।

३३४७। स्वादुमि णमुल्। ३। ४। २६। स्वाद्वर्थेषु कृञो णमुल्स्यादेककर्तृकयोः पूर्वकाले। पूर्वपदस्य मान्तत्वं निपात्यते। अस्वादुं स्वादुं कृत्वा भुङ्क्ते स्वादुंकारं भुङ्क्ते। संपन्नंकारम्। लवणंकारम्। संपन्नलवणशब्दौ स्वादुपर्यायौ। वासरूपेण क्त्वापि। स्वादुं कृत्वा भुङ्क्ते।

३३४८। अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्। ३। ४। २७। एषु कृञो णमुल्स्यात् सिद्धोऽप्रयोगोऽस्यैवंभूतश्चेत्कृञ्। व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः। अन्यथाकारम्। एवंकारम्। कथंकारम्। इत्थंकारं भुङ्क्ते। इत्थं भुङ्क्त इत्यर्थः। 'सिद्ध—' इति किम्। शिरोऽन्यथा कृत्वा भुङ्क्ते।

३३४९। यथातथयोरसूयाप्रतिवचने। ३। ४। २८। कृञः सिद्धाप्रयोग इत्येव। असूयया प्रतिवचने। यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन।

३३५०। कर्मणि दृशिविदोः साकल्ये। ३। ४। २९। कर्मण्युपपदे णमुल्स्यात्। कन्यादर्शं वरयति। सर्वाः कन्या इत्यर्थः। ब्राह्मणवेदं भोजयति। यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः।

३३५१। यावति विन्दजीवोः। ३। ४। ३०। यावद्वेदं भुङ्क्ते। यावल्लभते तावदित्यर्थः। यावज्जीवमधीते।

३३५२। चर्मोदरयोः पूरेः। ३। ४। ३१। कर्मणीत्येव। चर्मपूरं स्तृणाति। उदरपूरं भुङ्क्ते।

३३५३। वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्। ३। ४। ३२। कर्मण्युपपदे पूरेर्णमुल्स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये। गोष्पदपूरं वृष्टो देवः। गोष्पदप्रं वृष्टो देवः। 'अस्य' इति किम्। उपपदस्य माभूत्। मूषिकाबिलप्रम्।

३३५४। चेले क्नोपेः। ३। ४। ३३। चेलार्थेषु कर्मसूपपदेषु क्नोपेर्णमुल्स्याद्वर्षप्रमाणे। चेलक्नोपं वृष्टो देवः। वस्त्रक्नोपम्। वसनक्नोपम्।

३३५५। निमूलसमूलयोः कषः। ३। ४। ३४। कर्मणीत्येव। कषादिष्वनुप्रयोगो वक्ष्यति। अत्र प्रकरणे पूर्वकाल इति न संबध्यते। निमूलकाषं कषति। समूलकाषं

कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसंबन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ।

३३५६ । शुष्कचूर्णरूक्षेषु पिषः । ३ । ४ । ३५ । एषु कर्मसु पिषेर्णमुल् । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ।

३३५७ । समूलाकृतजीवेषु हन्कृञ्ग्रहः । ३ । ४ । ३६ । कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ।

३३५८ । करणे हनः । ३ । ४ । ३७ । पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थःसन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसंबंधे तु 'हिंसार्थानां च-' (सू ३३६९) इति वक्ष्यते ।

३३५९ । स्नेहने पिषः । ३ । ४ । ३८ । स्निह्यते येन तस्मिन्करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ।

३३६० । हस्ते वर्तिग्रहोः । ३ । ४ । ३९ । हस्तार्थे करणे । हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ।

३३६१ । स्वे पुषः । ३ । ४ । ४० करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ।

३३६२ । अधिकरणे बन्धः । ३ । ४ । ४१ । चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ।

३३६३ । संज्ञायाम् । ३ । ४ । ४२ । बध्नातेर्णमुल्संज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिकाबन्धम् । बन्धविशेषाणां संज्ञा एताः ।

३३६४ । कर्त्रोर्जीवपुरुषयोर्नशिवहोः । ३ । ४ । ४३ । जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ।

३३६५ । ऊर्ध्वे शुषिपूरोः । ३ । ४ । ४४ । ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठञ्छुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ।

३३६६ । उपमाने कर्मणि च । ३ । ४ । ४५ । चात्कर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ।

३३६७ । कषादिषु यथाविध्यनुप्रयोगः । ३ । ४ । ४६ । यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ।

३३६८ । उपदंशस्तृतीयायाम् । ३ । ४ । ४७ । इतः प्रभृति पूर्वकाल इति संबध्यते । 'तृतीयाप्रभृतीन्यन्यतरस्याम्' (सू ७८४) इति वा समासः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दसंबन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थ्येन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ।

३३६९ । हिंसार्थानां च समानकर्मकाणाम् । ३ । ४ । ४८ । तृतीयान्त उपपदे-

ऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थायां णमुल्स्यात् । दण्डोपघातं गाः कालयति दण्डेनोपघातम् । दण्डताडम् । 'समानकर्मकाणाम्' इति किम् । दण्डेन चोरमाहत्य गाः कालयति ।

३३७० सप्तम्यां चोपपीडरुधकर्षः । ३ । ४ । ४९ । उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल्स्यात् । पार्श्वोपपीडं शेते-पार्श्वयोरुपपीडम्-पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन-व्रजे उपरोधं वा । पाण्युपकर्षं धानाः संगृह्णाति । पाणावुपकर्षम्-पाणिनोपकर्षम् ।

३३७१ । समासत्तौ । ३ । ४ । ५० । तृतीयासप्तम्योर्धातोर्णमुल्स्यात्संनिकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ।

३३७२ । प्रमाणे च । ३ । ४ । ५१ । तृतीयासप्तम्योरित्येव । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति । द्व्यङ्गुलेन द्व्यङ्गुले वोत्कर्षम् ।

३३७३ । अपादाने परीप्सायाम् । ३ । ४ । ५२ । परीप्सा त्वरा । शय्योत्थायं धावति ।

३३७४ । द्वितीयायां च । ३ । ४ । ५३ । परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ।

३३७५ । अपगुरो णमुलि । ६ । १ । ५३ । 'गुरी उद्यमने' इत्यस्यैचो वात्स्याण्णमुलि । अस्यपगोरं युध्यन्ते । अस्यपगारम् ।

३३७६ । स्वाङ्गेऽध्रुवे । ३ । ४ । ५४ । द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । भ्रुवं विक्षेपम् । 'अध्रुवे' किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्ध्रुवम् ।

३३७७ । परिक्लिश्यमाने च । ३ । ४ । ५५ । सर्वतो विबाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल्स्यात् । उरःप्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयन्त इत्यर्थः । 'उरोविदारं प्रतिचस्करे नखैः' । ध्रुवार्थमिदम् ।

३३७८ । विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः । ३ । ४ । ५६ । द्वितीयायामित्येव । द्वितीयान्त उपपदे विश्यादिभ्यो णमुल्स्याद्व्याप्यमान आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः । क्रियायाः पौनःपुन्यमासेवा । 'नित्यवीप्सयोः' (सू. २१४०)इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसंज्ञार्थमासेवायामिह पुनर्विधिः । गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ।

३३७९ । अस्यति तृषोः क्रियान्तरे कालेषु । ३ । ४ । ५७ । क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषूपपदेषु णमुल्स्यात् । द्व्यहात्यासं गाः पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहंतर्षम् अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ।

३३८० । नाम्न्यादिशिग्रहोः । ३ । ४ । ५८ । द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति ।

३३८१। अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ। ३।४।५९। अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य च नीचैः कथनम्। उच्चैःकृत्य-उच्चैःकृत्वा। उच्चैःकारमप्रियमाचष्टे। नीचैःकृत्य-नीचैःकृत्वा-नीचैः कारं प्रियं ब्रूते।

३३८२। तिर्यच्यपवर्गे। ३। ४। ६०। तिर्यक्छब्द उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम्। तिर्यक्कृत्य गतः। तिर्यक्कारम्। समाप्य गत इत्यर्थः। 'अपवर्गे' किम्। तिर्यक्कृत्वा काष्ठं गतः।

३३८३। स्वाङ्गे तस्प्रत्यये कृभ्वोः। ३। ४। ६१। मुखतःकृत्य गतः। मुखतः कृत्वा। मुखतः कारम्। मुखतोभूय। मुखतो भूत्वा। मुखतोभावम्।

३३८४। नाधार्थप्रत्यये च्व्यर्थे। ३। ४। ६२। नाधार्थप्रत्ययान्ते च्व्यर्थविषय उपपदे कृभुवोः क्त्वाणमुलौ स्तः। अनाना नाना कृत्वा नानाकृत्य नाना कृत्वा-नानाकारम्। विनाकृत्य-विना कृत्वा-विनाकारम्। नानाभूय-नाना भूत्वा-नानाभावम्। अनेकं द्रव्यमेकं भूत्वा एकधाभूय-एकधा भूत्वा-एकधाभावम्। एकधाकृत्यएकधा कृत्वा-एकधाकारम्। 'प्रत्ययग्रहणम्' किम्। हिरुक्कृत्वा। पृथग्भूत्वा।

३३८५। तूष्णीमि भुवः। ३। ४। ६३। तूष्णींशब्दे भुवः क्त्वाणमुलौ स्तः। तूष्णींभूय-तूष्णीं भूत्वा-तूष्णींभावम्।

३३८६। अन्वच्यानुलोम्ये। ३। ४। ६४। अन्वक्छब्द उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने। अन्वग्भूय आस्ते। अन्वग्भूत्वा-अन्वग्भावम्। अग्रतः पार्श्वतः पृष्ठतो वानुकूलो भूत्वा आस्त इत्यर्थः। 'आनुलोम्ये' किम्। अन्वग्भूत्वा तिष्ठति। पृष्ठतो भूत्वेत्यर्थः।

इति कृदन्तप्रकरणम्।

इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम्।
विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे॥
भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी।
प्रीत्यै भूयाद्भगवतोर्भवानीविश्वनाथयोः॥

इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्धं समाप्तम्।

॥ वैयाकरणसिद्धान्तकौमुदी ॥

अथ वैदिकप्रकरणम् ।

३६८७ । छन्दसि पुनर्वस्वोरेकवचनम् । १ । २ । ६१ । द्वयोरेकवचनं वा स्यात् । पुनर्वसुर्नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ।

३३८८ । विशाखयोश्च । १ । २ । ६२ । प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ।

३३८९ । षष्ठीयुक्तश्छन्दसि वा । १ । ४ । ९ । षष्ठ्यन्तेन युक्तः 'पति'शब्दश्छन्दसि घिसंज्ञो वा स्यात् । 'क्षेत्रस्य पतिना वयम्' । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । 'सर्वे विधयश्छन्दसि वैकल्पिकाः' । तेन 'बहुलं छन्दसि' (सू ३४०१) इत्यादिरस्यैव प्रपञ्चः । 'यचि भम्' (सू २३१) । 'नभोऽङ्गिरोमनुषां वत्युपसंख्यानम्' (वा १०५८) नभसा तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः । 'अङ्गिरस्वदङ्गिरः' । 'मनुष्वदग्ने' । 'जनेरुसिः' (उणा) इति विहित उसिप्रत्ययो मनेरपि बाहुलकात् । 'वृषण्वस्वश्वयोः' (वा १०५९) । वृष वर्षकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्य वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव 'पदान्तस्य' (सू १९८) इति णत्वनिषेधोऽपि न । 'अल्लोपोऽनः' (सू २३४) इत्यल्लोपो नानङ्गत्वात् ।

३३९० । अयस्मयादीनि च्छन्दसि । १ । ४ । २० । एतानि च्छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोगं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम्—'उभयसंज्ञान्यपीति वक्तव्यम्' (वा १०६०) इति 'स सुष्टुभास ऋक्वता गणेन' । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । 'नैनं हिन्वन्त्यपि वाजिनेषु' । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । 'ते प्राग्धातोः' (सू २२३०) ।

३३९१ । छन्दसि परेऽपि । १ । ४ । ८१ ।

३३९२ । व्यवहिताश्च । १ । ४ । ८२ । 'हरिभ्यां याह्योक आ' । 'आ मन्द्रैरिन्द्र हरिभिर्याहि' ।

३३९३ । इन्धिभवतिभ्यां च । १ । २ । ६ । आभ्यां परो लिट् कित् । 'समीधे दस्युहन्तमम्' । 'पुत्र ईधे अथर्वणः' । बभूव । इदं प्रत्याख्यातम् । 'इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यम्' (वा ९९४) इति ।

इति प्रथमोऽध्यायः ।

३३९४ । तृतीया च होश्छन्दसि । २ । ३ । ३ । जुहोतेः कर्मणि तृतीया स्याद्द्वितीया च । 'यवाग्वाग्निहोत्रं जुहोति' । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । 'यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत' इत्यादिप्रयोगदर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ।

३३९५। द्वितीया ब्राह्मणे। २। ३। ६०। ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात्। षष्ठ्यपवादः। 'गामस्य तदहः सभायां दीव्येयुः'।

३३९६। चतुर्थ्यर्थे बहुलं छन्दसि। २। ३। ६२। षष्ठी स्यात्। 'पुरुषमृगश्चन्द्रमसे'। 'गोधा कालका दार्वाघाटस्ते वनस्पतीनाम्'। वनस्पतिभ्य इत्यर्थः। 'षष्ठ्यर्थे चतुर्थीति वाच्यम्' (वा १५०९)। 'या खर्वेण पिबति तस्यै खर्वः'।

३३९७। यजेश्च करणे। २। ३। ६३। इह छन्दसि बहुलं षष्ठी। घृतस्य। घृतेन वा यजते।

३३९८। बहुलं छन्दसि। २। ४। ३९। अदो घस्लादेशः स्यात्। घस्तां नूनम्। लुङि 'मन्त्रे घस–' (सू २४०२) इति च्लेर्लुक्। अडभावः। 'सग्धिश्च मे'।

३३९९। हेमन्तशिशिरावहोरात्रे च च्छन्दसि। २। ४। २८। द्वन्द्वः पूर्ववल्लिङ्गः। हेमन्तश्च शिशिरश्च हेमन्तशिशिरौ। अहोरात्रे। 'अदिप्रभृतिभ्यः शपः' (सू २४२३)।

३४००। बहुलं छन्दसि। २। ४। ७३। वृत्रं हनाति वृत्रहा। 'अहिः शयत उपपृक् पृथिव्याः'। अत्र लुङ्। अदादिभिन्नेऽपि क्वाचिल्लुक्। 'त्राध्वं नो देवाः'। 'जुहोत्यादिभ्यः श्लुः' (सू २४८९)

३४०१। बहुलं छन्दसि। २। ४। ७६। 'दाति प्रियाणि चिद्वसु'। अन्यत्रापि। 'पूर्णां विवष्टि'।

३४०२। मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः। २। ४। ८०। लिरिति च्लेः प्राचां संज्ञा। एभ्यो लेर्लुक्स्यान्मन्त्रे। 'अक्षन्नमी मदन्तहि'। घस्लादेशस्य 'गमहन–' (सू २३६३) इत्युपधालोपे 'शासिवसि–' (सू २४१०) इति षः। 'माह्वर्मित्रस्य'। 'धूर्तिः प्रणङ्मर्त्यस्य'। 'नशेर्वा' (सू ४३१) इति कुत्वम्। 'सुरुचो वेन आवः'। 'मा न आवृक्'। आदित्याकारान्तग्रहणम्। 'आप्रा द्यावापृथिवी'। 'परावर्ग्भारभृद्यथा'। 'अक्रन्नुषसः'। 'त्वे रयिं जागृवांसो अनुग्मन्'। मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम्। 'अज्ञत वा अस्यन्दताः'। विभाषानुवृत्तेर्नेह। 'न ता अगृभ्णन्नजनिष्ट हि षः'।

इति द्वितीयोऽध्यायः।

३४०३। अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि। ३। १। ४२। आद्येषु चतुर्षु लुङि 'आम्' 'अकः' इत्यनुप्रयोगश्च। अभ्युत्सादयामकः। अभ्युदसीषददिति लोके। प्रजनयामकः। प्राजीजनदित्यर्थः। चिकयामकः अचैषीदित्यर्थे चिनोतेराम्द्विर्वचनं कुत्वं च। रमयामकः। अरीरमत्। पावयांक्रियात्। पाव्यादिति लोके। विदामक्रन्। अवेदिषुः।

३४०४। गुपेश्छन्दसि। ३। १। ५०। च्लेश्चङ्। 'गृहानजूगुपतं युवम्'। अगोपिष्टमित्यर्थः।

३४०५। नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः। ३। १। ५१। च्लेश्चङ् न। 'मा त्वायतो जरितुः काममूनयीः'। 'मा त्वाग्निर्ध्वनयीत्'।

३४०६। कृमृदृरुहिभ्यश्छन्दसि। ३। १। ५९। च्लेरङ् वा। 'इदं तेभ्योकरं नमः'। अमरत्। अदरत्। 'यत्सानोः सानुमारुहत्'।

३४०७। छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ।३।१।१२३। कृन्ततेर्निस्पूर्वात्क्यपि प्राप्ते ण्यत्। आद्यन्तयोर्विपर्यासो निसः षत्वं च। 'निष्टर्क्यं चिन्वीत पशुकामः'। देवशब्द उपपदे ह्वयतेर्जुहोतेर्वा क्यप्दीर्घश्च। 'स्पर्द्धन्ते वा उ देवहूये'। 'प्र' 'उत्' आभ्यां नयतेः क्यप्। प्रणीयः। उन्नीयः। उत्पूर्वाच्छिषेः क्यप्। उच्छिष्यः। 'मृङ्' 'स्तृञ्' 'ध्वृ' एभ्यो यत्। मर्यः। स्तर्या। स्त्रियामेवायम्। ध्वर्यः। खनेर्यण्ण्यतौ। खन्यः। खान्यः। यजेर्यः। 'शुन्धध्वं दैव्याय कर्मणे देवयज्यायै'। आङ् पूर्वात्पृच्छेः क्यप्। 'आपृच्छ्यं धरुणं वाज्यर्षति'। सीव्यतेः क्यप्षत्वं च प्रतिषीव्यः। ब्रह्मणि वदेर्ण्यत्। ब्रह्मवाद्यम्। लोके तु 'वदः सुपि क्यप्च' (सू २८५४)इति क्यब्यतौ। भवतेः स्तौतेश्च ण्यत्। भाव्यः। स्ताव्यः।उपपूर्वाच्चिनोतेर्ण्यदायादेशश्च पृड उत्तरपदेऽपचाय्यपृडम्।'हिरण्य इति वक्तव्यम्' (वा १९४५) उपचेयपृडमेवान्यत्। 'मृड' सुखने 'पृड च' इत्यस्मादिगुपधलक्षणः कः।

३४०८। छन्दसि वनसनरक्षिमथाम् ।३।२।२७। एभ्यः कर्मण्युपपद इन्स्यात्। 'ब्रह्मवनिं त्वा क्षत्रवनिम् उत नो गोषणिं धियम्'। 'ये पथां पथिरक्षयः'। चतुरक्षौ। पथिरक्षी। 'हविर्मथीनामभि'।

३४०९। छन्दसि सहः ।३।२।६३। ण्विः स्यात्। पृतनाषाट्।

३४१०। वहश्च ।३।२।६४। प्राग्वत्। दित्यवाट्। योगविभाग उत्तरार्थः।

३४११। क्रव्यपुरीषपुरीष्येषु ञ्युट् ।३।२।६५। एषु वहेर्ञ्युट् स्याच्छन्दसि। कव्यवाहनः। पुरीषवाहनः। पुरीष्यवाहनः।

३४१२। हव्येऽनन्तःपादम् ।३।२।६६। अग्निर्नो हव्यवाहनः। पादमध्ये तु 'वहश्च' इति ण्विरेव। 'हव्यवाळग्निरजरः पिता नः'।

३४१३। जनसनखनक्रमगमो विट् ।३।२।६७। 'विड्वनोः–' (सू २९८२) इत्यात्वम्। अब्जा गोजाः। 'गोषा इन्द्रो नृषा असि'। 'सनोतेरनः' (सू३६४९) इति षत्वम्। 'इयं शुष्मेभिर्बिसखाइवारुजत्'। 'आ दधिक्राः शवसा पञ्च कृष्टीः'। अग्रेगाः।

३४१४। मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ।३।२।७१। 'श्वेतवहादीनां डस्पदस्येति वक्तव्यम्'। (वा २०३५–३६) यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस्वक्तव्य इत्यर्थः। श्वेतवाः। श्वेतवाहौ। श्वेतवाहः। उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः। उक्थशासौ। उक्थशासः। पुरो दाश्यते पुरोडाः।

३४१५। अवे यजः ।३।२।७२। अवयाः। अवयाजौ। अवयाजः।

३४१६। अवयाः श्वेतवाः पुरोडाश्च ।८।२।६७। एते संबुद्धौ कृतदीर्घा निपात्यन्ते। चादुक्थशाः।

३४१७। विजुपे छन्दसि ।३।२।७३। उप उपपदे यजेर्विच्। उपयट्।

३४१८। आतो मनिन्क्वनिब्वनिपश्च ।३।२।७४। सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः। चाद्विच्। सुदामा। सुधीवा। सुपीवा। भूरिदावा। घृतपावा। विच् कीलालपाः।

३४१९। बहुलं छन्दसि ।३।२।८८। उपपदान्तरेऽपि हन्तेर्बहुलं क्विप्स्यात्। मातृ-

हा । पितृहा । 'छन्दसि लिट्' (सू ३०९३) भूतसामान्ये । 'अहं द्यावापृथिवी आततान'। 'लिटः कानज्वा' (सू ३०९४)। 'क्वसुश्च' (सू ३०९५)। छन्दसि लिटः कानच्क्वसू वा स्तः। 'चक्राणा वृष्णि'। 'यो नो अग्ने अररिवाँ अघायुः' । 'छन्दस्यघशब्दात्परेच्छायां क्यच्क्यङ्‌। न्यः' (वा १०११)। 'क्याच्छन्दसि (सू ३१५०)। उप्रत्ययः स्यात्। अघायुः। 'एरजधिकारे जवसवौ छन्दसि वाच्यौ' (वा २२००)। 'ऊर्वोरस्तु मे जवः'। 'देवस्य सवितुः सवे'।

३४२०। मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः।३।३।९६। वृषादिभ्यः क्तिन्स्यात स चोदात्तः। 'वृष्टिं दिवः'। 'सुम्नमिष्टये'। 'पचत्पक्तीरुत'। 'इयं ते नव्यसी मतिः'। वित्तिः। भूतिः। 'अग्न आ याहि वीतये'। 'रातौ स्याभोभयासः'।

३४२१। छन्दसि गत्यर्थेभ्यः। ३। ३। १२९। ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच्स्यात् खलोऽपवादः। सूपसदनोऽग्निः।

३४२२। अन्येभ्योऽपि दृश्यते। ३ । ३ । १३० । गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच्स्यात्। 'सुवेदनामकृणोर्ब्रह्मणे गाम्'।

३४२३। छन्दसि लुङ्लङ्लिटः। ३। ४। ६। धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः। पक्षे यथास्वं प्रत्ययाः। लुङि। 'देवो देवेभिरागमत्'। लोडर्थे लुङ्। 'इदं तेभ्योऽकरं नमः'। लङ्। 'अग्निमद्य होतारमवृणीतायं यजमानः'। लिट्। 'अद्या ममार'। अद्य म्रियेत इत्यर्थः।

३४२४। लिङर्थे लेट्।३। ४। ७ विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि।

३४२५। सिब्बहुलं लेटि। ३। १। ३४।

३४२६। इतश्च लोपः परस्मैपदेषु। ३ । ४ । ९७ । लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु।

३४२७। लेटोऽडाटौ। ३। ४। ९४। लेटः 'अट्' 'आट्' एतावागमौ स्तः। तौ च पितौ। 'सिब्बहुलं णिद्वक्तव्यः' (वा १७९४)। वृद्धिः। 'प्र ण आयूंषि तारिषत्'। 'सुपेशसस्करति जोषिषद्धि'। 'आ साविषदर्शसानाय शरुम्'। सिप इलोपस्य चाभावे। 'पताति विद्युत्'। 'प्रियः सूर्ये प्रियो अग्ना भवाति'।

३४२८। स उत्तमस्य। ३। ४। ९८। लेडुत्तमसकारस्य वा लोपः स्यात्। करवाव। करवावः। टेरेत्वम्।

३४२९। आत ऐ। ३। ४। ९५। लेट आकारस्यै स्यात्। 'सुतेभिः सुप्रयसा मादयैते'। आतामित्याकारस्यैकारः। विधिसामर्थ्यादाट ऐत्वं न। अन्यथा हि ऐटमेव विदध्यात्। 'यो यजाति यजात इत्'।

३४३०। वैतोऽन्यत्र।३। ४। ९६। लेट एकारस्य 'ऐ' स्याद्वा। 'आत ऐ' (सू ३४२९) इत्यस्य विषयं विना। 'पशूनामीशै'। 'ग्रहा गृह्यान्तै'। 'अन्यत्र' किम्। 'सुप्रयसा मादयैते'।

३४३१। उपसंवादाशङ्कयोश्च। ३। ४। ८। पणबन्ध आशङ्कायां च लेट् स्यात्। 'अहमेव पशूनामीशै'। 'नेज्जिह्मायन्तो नरकं पताम'। 'हलः श्नः शानज्झौ' (सू २५५७)।

३४३२। छन्दसि शायजपि। ३। १। ८४। अपि शब्दाच्छानच्। 'गृभ्णाहि' ...छन्दसि

(वा ४८२३) इति हस्य भः । 'गृभाय जिह्वया मधु' । 'बधान देव सवितः' । 'अनिदिताम्–' (सू ४१५) इति बध्नातेर्नलोपः । 'गृभ्णामि ते' । 'मध्वा जभार' ।

३४३३ । व्यत्ययो बहुलम् । ३ । १ । ८५ । विकरणानां बहुलं व्यत्ययः स्याच्छन्दसि । 'आण्डा शुष्मस्य भेदति' । भिनत्तीति प्राप्ते । 'जरसा मरते पतिः' । म्रियत इति प्राप्ते । 'इन्द्रो वस्तेन नेषतु' । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । 'इन्द्रेण युजा तरुषेम वृत्रम्' । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उःशप्सिप्चेति त्रयो विकरणाः ।

"सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च ।

व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन" ॥ (भाष्यम्)

'धुरि दक्षिणायाः' । दक्षिणस्यामिति प्राप्ते । 'चषालं ये अश्वयूपाय तक्षति' । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । 'ब्रह्मचारिणमिच्छते' । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मिर्युध्यति' । युध्यत इति प्राप्ते । 'मधोस्तृप्ता इवासते' । मधुन इति प्राप्ते । नरः पुरुषः । 'अधा स वीरैर्दशभिर्वियूयाः' । वियूयादिति प्राप्ते । कालः कालवाची प्रत्ययः । 'श्वोऽग्नीनाधास्यमानेन' । लुटो विषये लट् । 'तमसो गा अदुक्षत्' । अधुक्षदिति प्राप्ते । 'मित्र वयं च सूरयः' । मित्रा वयमिति प्राप्ते । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषयेऽच् । अत्रग्रहे विशेषः । यङो यशब्दादारभ्य 'लिङ्याशिष्यङ्' (सू २४३४) इति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव

३४३४ । लिङ्याशिष्यङ् । ३ । १ । ८६ । आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम्' (सू २४५४) । 'मन्त्रं वोचेमाग्नये' । 'दृशेरग्वक्तव्यः' (वा १८६२) । 'पितरं च दृशेयं मातरं च' । अङि तु 'ऋदृशोऽङि–' (सू २४०६) इति गुणः स्यात् ।

३४३५ । छन्दस्युभयथा । ३ । ४ । ११७ । धात्वधिकार उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । 'वर्धन्तु त्वा सुष्टुतयः' । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । 'विशृण्विरे' । सार्वधातुकत्वाच्छ्नुः शृभावश्च । 'हुश्नुवोः–'(सू २३८७) इति यण् । 'आदृगमहनजनः किकिनौ लिट् च' (सू ३१५१) । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तः । तौ च लिड्वत् । 'बभ्रिर्वज्रम्' । 'पपिः सोमम्' । 'ददिर्गाः' । 'जग्मिर्युवा' । 'जघ्निर्वृत्रममित्रियम्' । जज्ञिः । लिड्वद्भावादेव सिद्धे 'ऋच्छत्यृताम्' (सू २३८३) इति गुणबाधनार्थं कित्त्वम् । 'बहुलं छन्दसि' (सू ३५७८) इत्युत्त्वम् । ततुरिः । जगुरिः ।

३४३६ । तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः । ३ । ४ । ९ । से । 'वक्षे रायः' । सेन् । 'ता वामेषे' । असे । 'शरदो जीवसे धाः' । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । 'गवामिव श्रियसे' । अध्यै । अध्यैन् । 'जठरं पृणध्यै' । पक्ष आद्युदात्तः । कध्यै । कध्यैन् । आहुवध्यै । पक्षे नित्स्वरः । शध्यै । 'राधसः सह मादयध्यै' । शध्यैन् । 'वायवे पिबध्यै' । तवै । दातवा उ । तवेङ् । सूतवे । तवेन् । कर्तवे ।

३४३७ । प्रयै रोहिष्यै अव्यथिष्यै । ३ । ४ । १० । एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः ।

३४३८ । दृशे विख्ये च । ३ । ४ । ११ । द्रष्टुं विख्यातुमित्यर्थः ।

३४३९ । शकि णमुल्कमुलौ । ३ । ४ । १२ । शक्नोतावुपपदे तुमर्थे एतौ स्तः । 'विभाजं नाशकत्' । 'अपलुपं नाशकत्' । विभक्तुमपलोप्तुमित्यर्थः ।

३४४० । ईश्वरे तोसुन्कसुनौ । ३ । ४ । १३ । 'ईश्वरो विचरितोः' । 'ईश्वरो विलिखः' । विचरितुं विलेखितुमित्यर्थः ।

३४४१ । कृत्यार्थे तवैकेन्केन्यत्वनः । ३ । ४ । १४ । 'न म्लेच्छितवै' । 'अवगाहे' । 'दिदृक्षेण्यः' । 'भूर्यस्पष्ट कर्त्वम्' ।

३४४२ । अवचक्षे च । ३ । ४ । १५ । 'रिपुणा नावचक्षे' । अवख्यातव्यमित्यर्थः ।

३४४३ । भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् । ३ । ४ । १६ । 'आसंस्थातोः सीदन्ति' । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । प्रवदितोः । प्रचरितोः । होतोः । आतमितोः । 'काममाविजनितोः संभवाम' इति श्रुतिः ।

३४४४ । सृपितृदोः कसुन् । ३ । ४ । १७ । भावलक्षण इत्येव । 'पुरा क्रूरस्य विसृपो विरप्शिन्' । 'पुरा जतृभ्य आतृदः' ।

इति तृतीयोऽध्यायः ।

३४४५ । रात्रेश्चाजसौ । ४ । १ । ३१ । रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । 'रात्री व्यख्यदायती' । लोके तु कृदिकारादिति ङीष्यन्तोदात्तः ।

३४४६ । नित्यं छन्दसि । ४ । १ । ४६ । बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । 'बह्वीषु हित्वा' । नित्यग्रहणमुत्तरार्थम् ।

३४४७ । भुवश्च । ४ । १ । ४६ । ङीष्स्यात् छन्दसि । विभ्वी । विप्रसंभ्वी इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः । 'मुद्गलाच्छन्दसि लिच्च' (वा २४७६) । ङीषो लित्त्वमानुक्चागमः । लित्स्वरः । 'रथीरभून्मुद्गलानी' ।

३४४८ । दीर्घजिह्वी च च्छन्दसि । ४ । १ । ५९ । संयोगोपधत्वादप्राप्तो ङीब्विधीयते । 'आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट्' ।

३४४९ । कद्रुकमण्डल्वोश्छन्दसि । ४ । १ । ७१ । ऊङ् स्यात् । 'कद्रूश्च वै कमण्डलूः' । 'गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्' (वा २५०४) । गुग्गुलूः । मधूः । जतूः । पतयालूः । 'अव्ययात्त्यप्' (सू १३२४) । 'आविष्ट्यस्योपसंख्यानं छन्दसि' (वा २७८९) । 'आविष्ट्यो वर्धते' ।

३४५० । छन्दसि ठञ् । ४ । ३ । १९ । वर्षाभ्यः । ठकोऽपवादः । स्वरे भेदः । वार्षिकम् ।

३४५१ । वसन्ताच्च । ४ । ३ । २० । ठञ्स्याच्छन्दसि । वासन्तिकम् ।

३४५२ । हेमन्ताच्च । ४ । ३ । २१ । छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः । 'शौनकादिभ्यश्छन्दसि' (सू १४८६) । णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । 'छन्दसि' किम् । शौनकीया शिक्षा ।

३४५३ । द्व्यचश्छन्दसि । ४ । ३ । १५० । विकारे मयट् स्यात् । शरमयं बर्हिः । 'यस्य पर्णमयी जुहूः' ।

३४५४ । नोत्वद्वर्ध्रबिल्वात् । ४ । ३ । । १५१ । उत्वानुकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । 'सभाया यः' (सू १६५७) ।

३४५५। ढश्छन्दसि। ४।४।१०६। 'सभेयो युवा'।

३४५६। भवे छन्दसि। ४।४।११०। सप्तम्यन्ताद्भवार्थे यत्। 'मेघ्याय च विद्युत्याय च'। यथायथं शैषिकाणामणादीनां चापवादोऽयं यत्। पक्षे तेऽपि भवन्ति। सर्वविधीनां छन्दसि वैकल्पिकत्वात्। तद्यथा मुञ्जवान्नाम पर्वतस्तत्र भवो मौञ्जवतः। 'सोमस्येव मौञ्जवतस्य भक्षः'। आचतुर्थसमाप्तेश्छन्दोऽधिकारः।

३४५७। पाथोनदीभ्यां ड्यण्। ४।४।१११। 'तमु त्वा पाथ्यो वृषा'। 'चनो दधीत नाद्यो गिरो मे'। पाथसि भवः पाथ्यः। नद्यां भवो नाद्यः।

३४५८। वेशन्तहिमवद्भ्यामण्। ४।४।११२। भवे। 'वैशन्तीभ्यः स्वाहा'। 'हैमवतीभ्यः स्वाहा'।

३४५९। स्रोतसो विभाषा ड्यड्ड्यौ। ४।४।११३। पक्षे यत्। ड्यड्ड्ययोस्तु स्वरे भेदः। स्रोतसि भवः स्रोत्यः-स्रोतस्यः।

३४६०। सगर्भसयूथसनुताद्यन्। ४।४।११४। अनुभ्राता सगर्भ्यः। अनुसखा सयूथ्यः। 'यो नः सनुत्य उत वा जिघत्नुः'। नुतिर्नुतम्। 'नपुंसके भावे क्तः' (सू३०९०)। सगर्भादयस्त्रयोऽपि कर्मधारयाः। 'समानस्य छन्दसि-' (सू१०१२) इति सः। ततो भवार्थे यन्। यतोऽपवादः।

३४६१। तुग्राद्घन्। ४।४।११५। भवेऽर्थे। पक्षे यदपि। 'आ वः शमं वृषभं तुग्र्यासु' इति बह्वृचाः। 'तुग्रियासु' इति शाखान्तरे। 'घनाकाशयज्ञवरिष्ठेषु तुग्रशब्दः' इति वृत्तिः।

३४६२। अग्राद्यत्। ४।४।११६।

३४६३। घच्छौ च। ४।४।११७। चाद्यत्। अग्रे भवोऽग्र्यः अग्रियः-अग्रीयः।

३४६४। समुद्राभ्राद्घः। ४।४।११८। 'समुद्रिया अप्सरसो मनीषिणम्'। 'नानदतो अभ्रियस्येव घोषाः'।

३४६५। बर्हिषि दत्तम्। ४।४।११९। प्राग्घिताद्यदित्येव। 'बर्हिष्येषु निधिषु प्रियेषु'।

३४६६। दूतस्य भागकर्मणी। ४।४।१२०। भागोंऽशः। दूत्यम्।

३४६७। रक्षोयातूनां हननी। ४।४।१२१। 'या तेऽग्ने रक्षस्या तनूः'। यातव्या।

३४६८। रेवतीजगतीहविष्याभ्यःप्रशस्ये। ४।४।१२२। प्रशंसने यत्स्यात्। रेवत्यादीनां प्रशंसनं रेवत्यम्। जगत्यम्। हविष्यम्।

३४६९। असुरस्य स्वम्। ४।४।१२३। 'असुर्यं देवेभिर्धायि विश्वम्'।

३४७०। मायायामण्। ४।४।१२४। आसुरी माया।

३४७१। तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः। ४।४।१२५। वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः। ऋतव्याः।

३४७२। अश्विमानण्। ४।४।१२६। 'आश्विनीरुपदधाति'।

३४७३ वयस्यासु मूर्ध्नो मतुप्। ४।४।१२७। तद्वानासामिति सूत्रं सर्वमनुवर्तते। मतोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यं। मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्। प्रथमस्य मतोर्लुक्च। वयश्शब्दवन्मन्त्रोपधेयास्विष्टकासु। यस्मिन्मन्त्रे मूर्धवयःशब्दौ स्तः, तेनोपधेयासु 'मूर्धन्वतीरुपदधाति' इति प्रयोगः।

३४७५। मत्वर्थे मासतन्वोः। ४। ४। १२८। नमोऽस्म्। तदस्मिन्नस्तीति नमस्यो मासः। ओजस्या तनूः।

३४७५। मधोर्ञ च। ४।४। १२९।चाद्यत्। माधवः—मधव्यः।

३४७६। ओजसोऽहनि यत्खौ। ४। ४। १३०। ओजस्यमहः। ओजसीनं वा।

३४७७। वेशोयशआदेर्भगाद्यल्। ४। ४। १३१। यथासङ्ख्यं[1] नेष्यते। वेशो बलं तदेव भगः। वेशोभग्यः। यशोभग्यः। वेशोभगीनः। यशोभगीनः।

(३४७८। ख च। ४।४। १३२। योगविभाग उत्तरार्थः। क्रमनिरासार्थश्च।)

३४७९। पूर्वैः कृतमिनयौ च। ४। ४। १३३। 'गम्भीरेभिः पथिभिः पूर्विणेभिः'। "येते पन्थाः सवितः पूर्व्यासः'।

३४८०। अद्भिः संस्कृतम्। ४। ४। १३४। 'यस्येदमप्यं हविः'

३४८१। सहस्रेण संमितौ घः। ४। ४। १३५। 'सहस्रियासोऽपां नोर्मयः'। सहस्रेण तुल्या इत्यर्थः।

३४८२। मतौ च। ४। ४।१३६। सहस्रशब्दान्मत्वर्थे घः स्यात्। सहस्रमस्यास्तीति सहस्रियः।

३४८३। सोममर्हति यः। ४। ४। १३७। सोम्यो ब्राह्मणः। यज्ञार्ह इत्यर्थः।

३४८४। मये च। ४। ४। १३८। सोमशब्दाद्यः स्यान्मयडर्थे। सोम्यं मधुः। सोममयमित्यर्थः।

३४८५। मधोः। ४। ४। १३९। मधुशब्दान्मयडर्थे यत्स्यात्। मधव्यः। मधुमय इत्यर्थः।

३४८६। वसोः समूहे च। ४। ४। १४०। चान्मयडर्थे यत्। वसव्यः। 'अक्षरसमूहे छन्दस उपसंख्यानम्' (वा २९८०)। छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः। ओश्रावय इति चतुरक्षरम्, 'अस्तुश्रौषट्' इति चतुरक्षरम्, 'येयजामहे' इति पञ्चाक्षरम्, "यज' इति द्व्यक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशाक्षरश्छन्दस्यः।

३४८७। नक्षत्राद्घः। ४। ४। १४१। स्वार्थे। 'नक्षत्रियेभ्यः स्वाहा'।

३४८८। सर्वदेवात्तातिल्। ४। ४। १४२। स्वार्थे। 'सविता नः सुवतु सर्वतातिम्'। प्रदक्षिणिद्देवतातिमुराणः'।

३४८९। शिवशमरिष्टस्य करे। ४। ४। १४३। करोतीति करः। पचाद्यच्। शिवं करोतीति शिवतातिः। 'याभिः शन्ताती भवथो ददाशुषे'। 'अथो अरिष्टतातये'।

३४९०। भावे च। ४। ४। १४४। शिवादिभ्यो भावे तातिः स्याच्छन्दसि। शिवस्य भावः शिवतातिः। शन्तातिः। अरिष्टतातिः।

इति चतुर्थोऽध्यायः।

३४९१। सप्तनोऽञ्छन्दसि। ५। १। ६१। 'तदस्य परिमाणम्' (सू १७२३) इति

---

१ "यथासंख्यमिति। वृत्तिकारस्तु'—यल्' 'ख च' इति सूत्रं व्यभजत्" इति मनोरमा। "वृत्तिकारास्त्विति। अत्रारुचिबीजं तु 'यथासंख्य'सूत्रस्थभाष्यविरोधः" इति शब्दरत्नम्। "यत्खाविति भाष्यपाठे' इत्यनुपदमेव मनोरमा।

'वर्गे' इति च । सप्त 'साप्तान्यसृजत्' । सप्तवर्गानित्यर्थः । 'शन्छतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः' (वा ३१३१) । पञ्चदशिनोऽर्धमासाः । त्रिंशिनो मासाः । 'विंशतेश्चेति वाच्यम्' (वा ३१३२) । विंशिनोऽङ्गिरसः । 'युष्मदस्मदोः सादृश्ये वतुब्वाच्यः' (वा ३१३८) । 'त्वावतः पुरूवसो' । 'न त्वावां अन्यः' । 'यज्ञं विप्रस्य मावतः' ।

३४९२ । छन्दसि च । ५ । १ । ६७ । प्रातिपदिकमात्रात् 'तदर्हति' इत्यर्थे यत्स्याच्छन्दसि । 'सादन्यं विदथ्यम्' ।

३४९३ । वत्सरान्ताच्छश्छन्दसि । ५ । १ । ९१ । निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ।

३४९४ । संपरिपूर्वात्ख च । ५ । १ । ९२ । चाच्छः । संवत्सरीणः-संवत्सरीयः । परिवत्सरीणः-परिवत्सरीयः ।

३४९५ । छन्दसि घस् । ५ । १ । १०६ । ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । 'भाग ऋत्वियः' ।

३४९६ । उपसर्गाच्छन्दसि धात्वर्थे । ५ । १ । ११८ । धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । 'यदुद्वतो निवतः' । उद्गतान्निर्गतादित्यर्थः ।

३४९७ । थट् च च्छन्दसि । ५ । २ । ५० । नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम्-पञ्चमम् । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (सू १८८९) 'पर्यवस्थाता शत्रुः' । 'अपत्यं परिपन्थिनम्' । 'मा त्वा परिपरिणो विदन्' ।

३४९८ । बहुलं छन्दसि । ५ । २ । १२२ । मत्वर्थे विनिः स्यात् । 'अग्निस्ते ओजस्वी' । 'छन्दोविन्प्रकरणे अष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम्' (वा ३२११) इति दीर्घः । 'मंहिष्ठमुभयाविनम्' । 'शुनमष्ट्राव्यचरत्' । 'छन्दसीवनिपौ च वक्तव्यौ' (वा ३२०२) । ई । 'रथीरभूत्' । 'सुमङ्गलीरियं वधूः' । 'मघवानमीमहे' ।

३४९९ । तयोर्दार्हिलौ च च्छन्दसि । ५ । ३ । २० । इदंतदोर्यथासंख्यं स्तः । 'इदा हि व उपस्तुतिम्' । तर्हि ।

३५०० । था हेतौ च च्छन्दसि । ५ । ३ । २६ । किमस्था स्याद्धेतौ प्रकारे च । 'कथा ग्रामं न पृच्छसि' । 'कथा दाशेम' ।

३५०१ । पश्च पश्चा च च्छदन्सि । ५ । ३ । ३३ । अवरस्यास्तात्यर्थे निपातौ । 'पश्च हि सः' । 'नो ते पश्चा' । 'तुश्छदसि' (सू २००७) । तृजन्तात्तृन्नन्ताच इष्ठन्नीयसुनौ स्तः । 'आसुतिं करिष्ठः' । 'दोहीयसी धेनुः' ।

३५०२ । प्रत्नपूर्वविश्वेमात्थाल्छन्दसि । ५ । ३ । १११ । इवार्थे । 'तं प्रत्नथा पूर्वथा विश्वथेमथा' ।

३५०३ । अमु च च्छन्दसि । ५ । ४ । १२ । किमेत्तिङव्ययघादित्येव । 'प्रतं नय प्रतरम्' ।

३५०४ । वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि । ५ । ४ । ४१ । स्वार्थे । 'यो नो दुरेवो वृकतिः' । 'ज्येष्ठतातिं बर्हिषदम्' ।

३५०५ । अनसन्तान्नपुंसकाच्छन्दसि । ५ । ४ । १०३ । तत्पुरुषाट्टच्स्यात्समासान्तः । 'ब्रह्मसामं भवति' । 'देवच्छन्दसानि' ।

३५०६ । बहुप्रजाश्छन्दसि । ५ । ४ । १२३ । 'बहुप्रजा निर्ऋतिमाविवेश' ।

३५०७ । छन्दसि च । ५ । ४ । १४२ । दन्तस्य दतृ स्याद्बहुव्रीहौ । 'उभयतोदतः प्रति गृह्णाति' ।

३५०८ । ऋतश्छन्दसि । ५ । ४ । १५८ । ऋदन्ताद्बहुव्रीहेर्न कप् । हता माता यस्य हतमाता ।

इति पञ्चमोऽध्यायः ।

'एकाचो द्वे प्रथमस्य' (सू २१७५) । 'छन्दसि वेति वक्तव्यम्' (वा ३४१४) । 'यो जागार' । 'दाति प्रियाणि' ।

३५०९ । तुजादीनां दीर्घोऽभ्यासस्य । ६ । १ । ७ । तुजादिराकृतिगणः । 'प्रभरा तूतुजानः' । 'सूर्यं मामहानम्' । 'दाधारः यः पृथिवीम्' । 'स तूताव' ।

३५१० । बहुलं छन्दसि । ६ । १ । ३४ । ह्वः संप्रसारणं स्यात् । 'इन्द्रमा हुव ऊतये' । 'ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि' (वा ३४७२) । ऋक्छब्दे परे त्रेः संप्रसारणमुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । 'छन्दसि' किम् । त्र्यृचानि । 'रयेर्मतौ बहुलम्' (वा ३४७३) । रेवान् । रयिमान्पुष्टिवर्धनः ।

३५११ । चायः की । ६ । १ । ३५ । चायतेर्बहुलं कीत्ययमादेशः स्याच्छन्दसि । 'न्यग्न्यञ्चिक्युर्न निचिक्युरन्यम्' । लिटच्युसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । 'अग्निं ज्योतिर्निचाय्य' ।

३५१२ । अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः । ६ । १ । ३६ । एते छन्दसि निपात्यन्ते । 'इन्द्रश्च विष्णो यदपस्पृधेथाम्' । स्पर्धेर्लङ्याथाम् । 'अर्कमानृचुः' । 'वसून्यानृहुः' । अर्चेरर्हेश्च लिटच्युसि । चिच्युषे । च्युङो लिटि थासि । 'यस्तित्याज' । त्यजेर्णलि । 'श्रातास्त इन्द्र सोमाः' । 'श्रिता नो ग्रहाः' । श्रीञ् पाके निष्ठायाम् । 'नाशिरं दुह्रे' । 'मध्यत आशीर्तः' । श्रीञ एव क्विपि निष्ठायां च ।

३५१३ । खिदेश्छन्दसि । ६ । १ । ५२ । 'खिद दैन्ये' । अस्यैच आ स्यात् । चिखाद । चिखेदेत्यर्थः ।

३५१४ । शीर्षंश्छन्दसि । ६ । १ । ६० । शिरःशब्दस्य शीर्षन् स्यात् । 'शीर्ष्णो जगतः' ।

३५१५ । वा छन्दसि । ६ । १ । १०६ । दीर्घाज्जसिचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । 'मानुषीरीळते विशः' । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामिपूर्वत्वं वा स्यात् । शमीं च शम्यं च । 'सूर्म्यं सुषिरामिव' । 'संप्रसारणाच्च' (सू ३३०) इति पूर्वरूपमपि वा । इज्यमानः—यज्यमानः ।

३५१६ । शेश्छन्दसि बहुलम् । ६ । १ । ७० । लोपः स्यात् । 'या ते गात्राणाम्' । 'ताता पिण्डानाम्' । 'एमन्नादिषु छन्दसि पररूपं वक्तव्यम्' (वा ३६३९) । अपां त्वेमन् । अपां त्वोद्मन् ।

३५१७ । भय्यप्रवय्ये च च्छन्दसि । ६ । १ । ८३ । बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । 'छन्दसि' किम् । भेयम् । प्रवेयम् । 'ह्रदय्या आप उपसंख्यानम्' (वा ३९४९) । ह्रदे भवा ह्रदय्या आपः । भवेः छन्दसि यत् ।

३५१८ । प्रकृत्यान्तःपादमव्यपरे । ६ । १ । ११५ । ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति । 'उपप्रयन्तो अध्वरम्' । 'सुजाते अश्व-

सूनृते'। 'अन्तःपादम्' किम्। 'एतास एतेऽर्चन्ति'। 'अव्यपरे' किम्। 'तेऽवदन्'। 'तेऽयजन्'।

३५१९। अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च। ६। १। ११६। एषु व्यपरेऽप्यति एङ् प्रकृत्या। 'वसुभिर्नो अव्यात्'। 'मित्रमहो अवद्यात्'। 'मा शिवासो अवक्रमुः'। 'ते नो अव्रत'। 'शतधारो अयं मणिः'। 'ते नो अवन्तु'। 'कुशिकासो अवस्यवः'। यद्यपि 'बह्वचैते नोऽवन्तु' 'रथतूः सोऽयमागात्' 'तेऽरुणेभिः' इत्यादौ प्रकृतिभावो न क्रियते' तथापि बाहुलकात्समाधेयम्। प्रातिशाख्ये तु वाचनिक एवायमर्थः।

३५२०। यजुष्युरः। ६। १। ११७। उरःशब्द एङन्तोऽति प्रकृत्या यजुषि। 'उरो अन्तरिक्षम्'। यजुषि पादाभावादनन्तःपादार्थं वचनम्।

३५२१। आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे। ६। १। ११८। यजुष्यति एङ् प्रकृत्या। 'आपो अस्मान्मातरः शुन्धयन्तु'। 'जुषाणो अग्निराज्यस्य'। 'वृष्णो अंशुभ्याम्'। 'वर्षिष्ठे अधि नाके'। 'अम्बे अम्बाले अम्बिके'। अस्मदेव वचनात् 'अम्बार्थ-' (सू २६७) इति ह्रस्वो न।

३५२२। अङ्ग इत्यादौ च। ६। १। ११९। अङ्गशब्दे य एङ् तदादौ चाकारे य एङ्पूर्वः सोऽति प्रकृत्या यजुषि। 'प्रणो अङ्गे अङ्गे अदीध्यत्'। 'अङ्गे अङ्गे अशोचिषम्'।

३५२३। अनुदात्ते च कुधपरे। ६। १। १२०। कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि। 'अयं सो अग्निः'। 'अयं सो अध्वरः'। 'अनुदात्ते' किम्। 'अधोऽग्ने रुद्रे'। अग्रशब्द आद्युदात्तः। 'कुधपरे' किम्। 'सोऽयमग्निमन्तः'।

३५२४ अवपथासि च। ६। १। १२१। अनुदात्ते अकारादौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या। 'त्री रुद्रेभ्यो अवपथाः'। वपेस्थासि लङि 'तिङ्ङतिङः' (सू ३९३९) इत्यनुदात्तत्वम्। 'अनुदात्ते' किम्। 'यद्रुद्रेभ्योऽवपथाः'। 'निपातैर्यद्यदि-' (सू ३९३७) इति निघातो न।

३५२५। आङोऽनुनासिकश्छन्दसि। ६। १। १२६। आङोऽचि परेऽनुनासिकः स्यात्। स च प्रकृत्या। 'अभ्र आँ अपः'। 'गभीर आँ उग्रपुत्रे'। 'ईषा अक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः' (वा ३६८५)। 'ईषाअक्षो हिरण्ययः'। 'ज्या इयम्'। 'पूषा आविष्टु'।

३५२६। स्यश्छन्दसि बहुलम्। ६। १। १३३। स्य इत्यस्य सोर्लोपः स्याद्धलि। 'एष स्य भानुः'।

३५२७। ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे। ६। १। १५१। ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे। 'हरिश्चन्द्रो मरुद्गणः'। सुश्चन्द्रस्य।

३५२८। पितरामातरा च छन्दसि ६। ३। ३३। द्वन्द्वे निपातः। 'आ मा गन्तां पितरामातरा च'। चाद्विपरीतमपि। 'न मातरापितरा नू चिदिष्टौ'। 'समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु' (सू १०१२)। समानस्य सः स्यान्मूर्धादिभिन्न उत्तरपदे। सगर्भ्यः। 'छन्दसि स्त्रियां बहुलम्' (वा ३९९४)। विष्वग्देवयोरद्र्यादेशः। 'विश्वाची च घृताची च'। 'देवद्रीचीं नयत देवयन्तः'। 'कद्रीची'।

३५२९। सध मादस्थयोश्छन्दसि। ६।३।९६। सहस्य सधादेशः स्यात्। 'इन्द्र त्वास्मिन्सधमाधे'। सोमः सधस्थम्।

३५३०। पथि च च्छन्दसि। ६।३।१०८। पथिशब्द उत्तरपदे कोः कवं कादेशश्च। कवपथः– कापथः–कुपथः।

३५३१। साढ्यै साढ्वा साढेति निगमे। ६।३।११३। सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते। 'मरुद्भिरुग्रः पृतनासु साळ्हा'। अचोर्मध्यस्थस्य डस्य ळः ढस्य ळ्हश्च प्रातिशाख्ये विहितः। आह हि।

'द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते। स डकारो ळकारः।

ळ्हकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्तेः॥' इति।

३५३२। छन्दसि च। ६।३।१२६। अष्टन आत्वं स्यादुत्तरपदे। अष्टापदी।

३५३३। मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ। ६।३।१३१। दीर्घः स्यान्मन्त्रे। 'अश्वावतीं सोमावतीम्'। इन्द्रियावान्मादिन्तमः। 'विश्वकर्मणा विश्वदेव्यावता'।

३५३४। ओषधेश्च विभक्तावप्रथमायाम्। ६।३।१३२। दीर्घः स्यान्मन्त्रे। 'यदोषधीभ्य अदधात्योषधीषु'।

३५३५। ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्। ६।३।१३३। दीर्घः स्यात्। 'आ तू न इन्द्र'। 'नू मर्तः'। 'उत वा घा स्यालात्'। मक्षू गोमन्तमीमहे। 'भरता जातवेदसम्'। तङिति थादेशस्य ङित्त्वपक्षे ग्रहणम्। तेनेह न। 'शृणोत ग्रावाणः'। 'कूमनाः'। 'अत्रा ते भद्रा'। 'यत्रा नश्चक्रा'। 'उरुष्याणः'।

३५३६। इकः सुञि। ६।३।१३४। ऋचि दीर्घ इत्येव। 'अभीषुणः सखीनाम्'। 'सुञः' (सू ३६४४) इति षः। 'नश्च धातुस्थोरुषुभ्यः' (सू ३६४९) इति णः।

३५३७। द्व्यचोऽतस्तिङः। ६।३।१३५। मन्त्रे दीर्घः। 'विद्मा हि चक्रा जरसम्'।

३५३८। निपातस्य च। ६।३।१३६। 'एवा हि ते'।

३५३९। अन्येषामपि दृश्यते। ६।३।१३७। अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात्। पूरुषः। दण्डादण्डि।

३५४०। छन्दस्युभयथा। ६।४।५। नामि दीर्घो वा। 'धाता धातॄणाम्' इति बह्वृचाः। तैत्तिरीयास्तु ह्रस्वमेव पठन्ति।

३५४१। वा षपूर्वस्य निगमे। ६।४।९। षपूर्वस्यान उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे। ऋभुक्षाणम्। ऋभुक्षणम्। 'निगमे' किम्। तक्षा। तक्षाणौ।

३५४२। जनिता मन्त्रे। ६।४।५३। इडादौ तृचि णिलोपो निपात्यते। 'योनः पिता जनिता'।

३५४३। शमिता यज्ञे। ६।४।५४। शमयितेत्यर्थः।

३५४४। युप्लुवोर्दीर्घश्छन्दसि। ६।४।५८। ल्यपीत्यनुवर्तते। वियूय। विप्लूय। 'आङजादीनाम्' (सू २२५४)।

३५४५। छन्दस्यपि दृश्यते। ६।४।७३। अनजादीनामित्यर्थः। आनट्। आवः। 'न माङ्योगे' (सू २२२८)।

३५४६ । बहुलं छन्दस्यमाङ्योगेऽपि । ६ । ४ । ७५ । अडाटौ न स्तः । माङ्योगेऽपि स्तः । 'जनिष्ठा उग्रः सहसे तुराय' । 'मा वः क्षेत्रे परबीजान्यवाप्सुः' ।

३५४७ । इरयो रे । ६ । ४ । ७६ । 'प्रथमं गर्भं दध्र आपः' । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावः । तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ।

३५४८ । छन्दस्युभयथा । ६ । ४ । ८६ । भूसुधियोर्यण्स्यादियङुवङौ च । 'वनेषु चित्रं विभ्वम्' । विभुवं वा । 'सुध्यो हव्यमग्ने' । सुधियो वा । 'तन्वादीनां छन्दसि बहुलम्' (वा ४११५) । 'तन्वं पुषेम' । तनुवं वा । त्र्यम्बकम्–त्रियम्बकं वा ।

३५४९ । तनिपत्योश्छन्दसि । ६ । ४ । ९९ । एतयोरुपधालोपः क्ङिति प्रत्यये । 'वितत्निरे कवयः' । 'शकुना इव पप्तिम' । भाषायां वितेनिरे । पेतिम ।

३५५० । घसिभसोर्हलि च । ६ । ४ । १०० । 'सग्धिश्च मे' । 'बब्धां ते हरी धानाः' । 'हुझल्भ्यो हेर्धिः' (सू २४२५) ।

३५५१ । श्रुशृणुपॄकृवृभ्यश्छन्दसि । ६ । ४ । १०२ । 'श्रुधी हवम्' । 'शृणुधी गिरः' । रायस्पूर्धि' । 'उरुणस्कृधि' । अपावृधि ।

३५५२ । वा छन्दसि । ६ । ४ । ८८ । हिरपिद्वा ।

३५५३ । अङितश्च । ६ । ४ । १०३ । हेर्धिः स्यात् । रारन्धि । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । 'अस्मे प्रयन्धि' । 'युयोधि जातवेदः' । यमेः शपो लुक् । यौतेः शपः श्लुः । 'अङितः' किम् । प्रणीहि ।

३५५४ । मन्त्रेष्वाङ्यादेरात्मनः । ६ । ४ । १४१ । आत्मन्शब्दस्यादेर्लोपः स्यादाङि । 'त्मना देवेषु' ।

३५५५ । विभाषर्जोश्छन्दसि । ६ । ४ । १६२ । ऋजुशब्दस्यर्तः स्थाने रः स्याद्वा इष्ठेमेयस्सु । त्वं 'रजिष्ठमनुनेषि' । ऋजिष्ठं वा ।

३५५६ । ऋव्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि । ६ । ४ । १७५ । ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् । वास्त्वं च मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते । 'माध्वीर्नः सन्त्वोषधीः' । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । 'हिरण्ययेन सविता रथेन' ।

इति षष्ठोऽध्यायः ।

'शीङो रुट्' (सू २४४२) ।

३५५७ । बहुलं छन्दसि । ७ । १ । ८ । रुडागमः स्यात् । 'लोपस्त आत्मनेपदेषु' (सू ३५६३) इति पक्षे तलोपः । 'धेनवो दुह्रे' । 'लोपाभावे घृतं दुह्रते' । 'अदृश्रमस्य' । 'अतो भिस ऐस्' (सू २०३) ।

३५५८ । बहुलं छन्दसि । ७ । १ । १० । 'अग्निर्देवेभिः' ।

३५५९ । नेतराच्छन्दसि । ७ । १ । २६ । स्वमोरदड् न । 'वार्त्रघ्नमितरम्' । 'छन्दसि' किम् । इतरत्काष्ठम् । 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' (सू ३३३२) ।

३५६० । क्त्वापि च्छन्दसि । ७ । १ । ३८ । यजमानं परिधापयित्वा ।

३५६१ । सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः । ७ । १ । ३९ । 'ऋजवः सन्तु पन्थाः' । पन्थान इति प्राप्ते सुः । 'परमे व्योमन्' । 'व्योमनि' इति प्राप्ते ङेर्लुक् । धीती । मती । सुष्टुती । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घः । 'या सुरथा रथीतमा दिविस्पृशा अश्विना' । 'यौ सुरथौ दिविस्पृशौ' इत्यादौ प्राप्ते आ । 'नताद्ब्राह्मणम्' । नतामिति प्राप्ते आत् । 'यादेव विद्म तात्वा' । यमिति प्राप्ते । 'युष्मे वाजबन्धवः' । 'अस्मे इन्द्राबृहस्पती' । युष्मास्वस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया उरुणा । धृष्णुनेति प्राप्ते या । 'नाभा पृथिव्याः' । नाभाविति प्राप्ते डा । 'ता अनुष्ठयोच्यावयतात्' । अनुष्ठानमनुष्ठा । व्यवस्थावदङ् । आङ्डयाः । साधुया । साध्विति प्राप्ते याच् । 'वसन्ता यजेत' । वसन्त इति प्राप्ते आल् । 'इयाडियाजीकाराणामुपसंख्यानम्' (वा ४३०८) । उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया । सुक्षेत्रिणेति प्राप्ते डियाच् । 'दृतिं न शुष्कं सरसी शयानम्' । ङेरीकार इत्याहुः । तन्नाद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तान्ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् । 'आङ्याजयारामुपसंख्यानम्' (वा ४३०९) । 'प्रबाहवा सिसृतम्' । बाहुनेति प्राप्ते आङादेशः । 'घेर्ङिति' (सू २४५) इति गुणः । स्वप्नया । स्वप्नेनेति प्राप्तेऽयाच् । 'स नः सिन्धुमिव नावया' । नावेति प्राप्तेऽयार् । रित्स्वरः ।

३५६२ । अमो मश् । ७ । १ । ४० । मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । 'अस्तिसिचः–' (सू २२२५) इति ईट् । 'वधीं वृत्रम्' । अवधिषमिति प्राप्ते ।

३५६३ । लोपस्त आत्मनेपदेषु । ७ । १ । ४१ । छन्दसि । 'देवा अदुह्र' । अदुह्रतेति प्राप्ते । 'दक्षिणतः शये' । शेत इति प्राप्ते । 'आत्मने–' इति किम् । 'उत्सं दुहन्ति' ।

३५६४ । ध्वमो ध्वात् । ७ । १ । ४२ । ध्वमो ध्वादित्यादेशः स्याच्छन्दसि । 'अन्तरेवोष्माणं वारयध्वात्' । वारयध्वमिति प्राप्ते ।

३५६५ । यजध्वैनमिति च । ७ । १ । ४३ । एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । 'यजध्वैनं प्रियमेधाः' । 'वकारस्य यकारो निपात्यते' इति वृत्तिकारोक्तिः प्रामादिकी ।

३५६६ । तस्य तात् । ७ । १ । ४४ । लोटो मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । 'गात्रमस्यानूनं कृणुतात्' । कृणुतेति प्राप्ते । 'सूर्यं चक्षुर्गमयतात्' । गमयतेति प्राप्ते ।

३५६७ । तप्तनप्तनथनाश्च । ७ । १ । ४५ । तस्येत्येव । शृणोत ग्रावाणः । शृणुतेति प्राप्ते तप् । 'सुनोत न पचत ब्रह्मवाहसे' । 'दधातन द्रविणं चित्रमस्मै' । तनप् । 'मरुतस्तज्जुजुष्टन' । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । 'विश्वे देवासो मरुतो यति ष्ठन' । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छान्दसो डतिः । अस्तेस्तस्य थनादेशः ।

३५६८ । इदन्तो मसि । ७ । १ । ४६ । मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मसित्ययमिकाररूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । 'नमो भरन्त एमसि' । 'त्वमस्माकं तव स्मसि' । 'इमः' 'स्मः' इति प्राप्ते ।

३५६९ । क्त्वो यक् । ७ । १ । ४७ । 'दिवं सुपर्णो गत्वाय' ।

३५७० । इष्ट्वीनमिति च । ७ । १ । ४८ । क्त्वाप्रत्ययस्य ईनमन्तादेशो निपात्यते । 'इष्ट्वीनं देवान्' । इष्ट्वेति प्राप्ते ।

३५७१। स्नात्व्यादयश्च। ७। १। ४९। आदिशब्दः प्रकारार्थः। आकारस्यैकारो निपात्यते। 'स्विन्नः स्नात्वी मलादिव'। 'पीत्वी सोमस्यवावृधे'। स्नात्वा पीत्वेति प्राप्ते।

३५७२। आज्जसेरसुक्। ७। १। ५०। अवर्णान्तादङ्गात्परस्य जसोऽसुक्स्यात्। देवासः। ब्राह्मणासः।

३५७३। श्रीग्रामण्योश्छन्दसि। ७। १। ५६। आमो नुट्। 'श्रीणामुदारो धरुणो रयीणाम्'। 'सूत ग्रामणीनाम्'।

३५७४। गोः पादान्ते। ७। १। ५७। 'विद्मा हि त्वा गोपतिं शूर गोनाम्'। 'पादान्ते' किम्। 'गवां शता पृक्षयामेषु'। पादान्तेऽपि क्वचिन्न। छन्दसि सर्वेषां वैकल्पिकत्वात्। 'विराजं गोपतिं गवाम्'।

३५७५। छन्दस्यपि दृश्यते। ७। १। ७६। अस्थ्यादीनामनङ्। 'इन्द्रो दधीचो अस्थभिः'।

३५७६। ई च द्विवचने। ७। १। ७७। अस्थ्यादीनामित्येव। 'अक्षीभ्यां ते नासिकाभ्याम्'।

३५७७। दृक्स्ववःस्वतवसां छन्दसि। ७। १। ८३। एषां नुम्स्यात्सौ। 'कीदृङ्ङिन्द्रः'। स्ववान्। स्वतवान्। 'उदोष्ठ्यपूर्वस्य' (सू २४९४)।

३५७८। बहुलं छन्दसि। ७। १। १०३। ततुरिः।

३५७९। ह्रु ह्वरेश्छन्दसि। ७। २। ३१। ह्वरेर्निष्ठायां 'ह्रु'आदेशः स्यात्। 'अह्रुतमसि हविर्धानम्'।

३५८०। अपरिह्वृताश्च। ७। २। ३२। पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते। 'अपरिह्वृताः सनुयाम वाजम्'।

३५८१। सोमे ह्वरितः। ७। २। ३३। इड्गुणौ निपात्येते। 'मा नः सोमो ह्वरितः'।

३५८२। ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमित्यमितीति च। ७। २। ३४। अष्टादश निपात्यन्ते। तत्र 'ग्रसु' 'स्कभु' 'स्तभु' एषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्त इण्निपात्यते। 'युवं शचीभिर्ग्रसितामभुञ्चतम्'। 'विष्कभिते अजरे'। 'येन स्वः स्तभितम्'। 'सत्येनोत्तभिता भूमिः'। स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति। 'चते याचने'। 'कस गतौ'। आभ्यां क्तस्येडभावः। 'चत्ता इतश्चत्तामुतः'। 'त्रिधा ह श्यावमश्विना विकस्तम्'। 'उत्तानाया हृदयं यद्विकस्तम्'। निपातनबहुत्वापेक्षया सूत्रे बहुवचनं विकस्ता इति, तेनैकवचनान्तोऽपि प्रयोगः साधुरेव। 'शसु' 'शंसु' 'शासु' एभ्यस्तृच इडभावः। 'एकस्त्वष्टुरश्वस्याविशस्ता'। 'ग्रावग्राभ उत शंस्ता'। 'प्रशास्ता पोता'। तरतेर्वृङ्वृञोश्च तृच 'उट्' 'ऊट्' एतावागमौ निपात्येते। 'तरुतारं रथानाम्'। तरूतारम्। वरुतारम्-वरूतारम्। 'वरूत्रीभिः सुशरणो नो अस्तु'। अत्र ङीबन्तनिपातनं प्रपञ्चार्थम्। वरूतृशब्दो हि निपातितः। ततो ङीपा गतार्थत्वात्। उज्ज्वलादिभ्यश्चतुर्भ्यः शप इकारादेशो निपात्यते। 'ज्वल दीप्तौ'। 'क्षर संचलने'। 'टुवम् उद्गिरणे' 'अम गत्यादिषु'। इह क्षरिनीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति। तत्र 'क्षमूष् सहने' इति धातुर्बोध्यः। भाषायां तु 'ग्रस्तस्कब्ध

स्तब्धो त्तब्धचतितविकासिताः'। विशासिता-शंसिता-शासिता। तरीता-तरिता। वरीता-वरिता। उज्ज्वलति। क्षरति। पाठान्तरे क्षमति। वमति। अमति।' बभूथाततन्थजगृभ्मववर्थेति निगमे' (सू २९२७)। 'विद्मा तमुत्सं यत आबभूथ'। 'येनान्तरिक्षमुर्वाततन्थ'। 'जगृभ्मा ते दक्षिणमिन्द्र हस्तम्'। 'त्वं ज्योतिषा वितमो ववर्थ'। भाषायां तु। बभूविथ। आतेनिथ। जगृहिम। ववरिथेति।

३५८३। सनिंससनिवांसम्। ७। २। ६९। सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा क्वसोरिट्। एत्त्वाभ्यासलोपाभावश्च निपात्यते। (अग्निस्त्वाग्ने सनिंससनिवांसम्)। 'पावकादीनां छन्दसि' (वा ४९२७) प्रत्ययस्थात्कादित्वं नेति वाच्यम्। 'हिरण्यवर्णाः शुचयः पावकाः'।

३५८४। घोर्लोपो लेटि वा। ७। ३। ७०। 'दधद्रत्नानि दाशुषे'। 'सोमो ददद्गन्धर्वाय'। 'यदग्निरग्नये ददात्'।

३५८५। मीनातेर्निगमे। ७। ३। ८१। शिति ह्रस्वः। 'प्रमिनन्ति व्रतानि'। लोके प्रमीणाति। 'अस्तिसिचोऽपृक्ते' (सू २२२५)।

३५८६। बहुलं छन्दसि। ७। ३। ९७। 'सर्वमा इदम्'। (अस्तेर्लङ् तिप् ईडभाव अपृक्तत्वाद्धल्ङ्यादिलोपः। रुत्वविसर्गौ। संहितायां तु 'भोभगो-' (सू १६७) इति यत्वम्। 'लोपः शाकल्यस्य' (सू ६७) इति यलोपः)। गोभिरक्षाः। सिच इडभावश्छान्दसः अट्। शेषं पूर्ववत्। 'ह्रस्वस्य गुणः' (सू २४२)। 'जसि च' (सू २४१)। 'जसादिषु छन्दसि वा वचनं प्राङ् णौ चङ्युपधायाः' (वा ४९९६)। 'अधा शतक्रत्वो यूयम्'। शतक्रतवः। 'पश्वे नृभ्यो यथा गवे'। पशवे। 'नाभ्यस्तस्याचि-' (सू २५०२) इति निषेधे 'बहुलं छन्दसीति वक्तव्यम्' (वा ४९८६)। 'आनुषग्जुजोषत्'।

३५८७। नित्यं छन्दसि। ७। ४। ८। छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋन्नित्यम्। अवीवृधत्।

३५८८। न च्छन्दस्यपुत्रस्य। ७। ४। ३५। पुत्रभिन्नस्यादन्तस्य क्यचीत्वदीर्घौ न। मित्रयुः। 'क्याच्छन्दसि' (सू ३१५०) इति उः। 'अपुत्रस्य' किम्। 'पुत्रीयन्तः' सुदानवः। 'अपुत्रादीनामिति वाच्यम्' (वा ४६१६)। 'जनीयन्तोऽन्वग्रवः'। जनमिच्छन्त इत्यर्थः।

३५८९। दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति। ७। ४। ३६। एते क्यचि निपात्यन्ते। भाषायां तु उप्रत्ययाभावाद्दुर्यीयति। द्रविणीयति। वृषीयति। रिष्टीयति।

३५९०। अश्वाघस्यात्। ७। ४। ३७। 'अश्व' 'अघ' एतयोः क्यच्यात्स्याच्छन्दसि। 'अश्वायन्तो मघवन्'। 'मा त्वा वृका अघायवः'। 'न च्छन्दसि-' (सू ३५८८) इति निषेधो नेत्त्वमात्रस्य। किंतु दीर्घस्यापीति। अत्रेदमेव सूत्रं ज्ञापकम्।

३५९१। देवसुम्नयोर्यजुषि काठके। ७। ४। ३८। अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम्। 'देवायन्तो यजमानाः'। 'सुम्नायन्तो हवामहे'। इह यजुः शब्दो न मन्त्रमात्रपरः किं तु वेदोपलक्षकः। तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति। किं च ऋग्वेदेऽपि भवति। सिचेन्मन्त्र यजुषि कठशाखायां दृष्टः। 'यजुषि' इति किम्। 'देवाञ्जिगाति सुम्नयुः'। बह्वृचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः।

३५९२। कव्यध्वरपृतनस्यर्चि लोपः। ७। ४। ३९। 'कवि'। 'अध्वर' 'पृतना'

तृशमन्त्यस्य लोपः स्यात्क्याचि परे ऋचि विषये। 'स पूर्व्या निविदा कव्यतायोः'। 'अध्वर्युं वा मधुपाणिम्'। 'दमयन्तं पृतन्युम्'। 'दधातेर्हिः' (सू ३०७६)। 'जहातेश्च क्त्वि' (सू ३३३१)।

३५९३। विभाषा छन्दसि। ७।४।४४। 'हित्वा शरीरम्'। हीत्वा वा।

३५९४। सुधितवसुधितनेमधितधिष्वधिषीय च। ७।४।४५। 'सु' 'वसु' 'नेम' एतत्पूर्वस्य दधातेः क्ते प्रत्यय इत्त्वं निपात्यते। 'गर्भं माता सुधितं वक्षणासु'। वसुधितमग्नौ। नेमधिता न पौंस्या। 'क्विन्यपि दृश्यते'। 'उत श्वेतं वसुधितिं निरेके'। 'धिष्व वज्रं दक्षिण इन्द्र हस्ते'। धत्स्वेति प्राप्ते। 'सुरेता रेतो धिषीय'। आशीर्लिङ्। इट्। 'इटोऽत्' (सू २२५७) धासीयेति प्राप्ते। 'अपो भि' (सू ४४२)। 'मासश्छन्दसीति वक्तव्यम्' (वा ४६३३)। माद्भिः शरद्भिः। 'स्ववःस्वतवसोरुषसश्चेष्यते' (वा ४६३४)। स्ववद्भिः। अवतेरसुन्। शोभनमवो येषां ते स्ववसस्तैः। 'तु' इति सौत्रो धातुस्तस्मादसुन्। स्वं तवो येषां तैः स्वतवद्भिः। 'समुषद्भिरजायथाः'। 'मिथुनेऽसिः'। 'वसेः किच्च' इत्यसिप्रत्यय इति हरदत्तः। पञ्चपादीरीत्या तु 'उषः कित्' इति प्राग्व्याख्यातम्। 'न कवतेर्यङि' (सू २६४१)।

३५९५। कृषेश्छन्दसि। ७।४।६४। यङ्यभ्यासस्य चुत्वं न। करीकृष्यते।

३५९६। दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च। ७।४।६५। एतेऽष्टादश निपात्यन्ते। आद्यास्त्रयो धृङो धारयतेर्वा। भवतेर्यङ्लुगन्तस्य गुणाभावः। तेन भाषायां गुणो लभ्यते। तिजेर्यङ्लुगन्तात्तङ्। इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते। 'अलर्षियुध्म खजकृत्पुरन्दरः'। सिपा निर्देशो न तन्त्रम्। 'अलर्ति दक्ष उत'। फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतर्यभ्यासस्य नीगागमो निपात्यते। 'अन्वापनीफणत्'। स्यन्देः संपूर्वस्य यङ्लुकि शतर्यभ्यासस्य निक्। धातुसकारस्य षत्वम्। करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः। 'करिक्रत्'। क्रन्देर्लुङि च्लेरङ् द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च। 'कनिक्रदज्जनुषम्'। अक्रन्दीदित्यर्थः। बिभर्तेरभ्यासस्य जश्त्वाभावः। 'वि यो भरिभ्रदोषधीषु'। ध्वरतेर्यङ्लुगन्तस्य शतर्यभ्यासस्य विगागमो धातोर्ऋकारलोपश्च। 'दविध्वतो रश्मयः सूर्यस्य'। द्युतेरभ्यासस्य संप्रसारणाभावोऽत्त्वं विगागमश्च 'दविद्युतद्दीद्यच्छोशुचानः'। तरतेः शतरि श्लावभ्यासस्य रिगागमः। 'सहोर्जा तरित्रतः'। सृपेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य। वृजेः शतरि श्लावभ्यासस्य रीक्। मृजेर्लिटि णलभ्यासस्य रुक् धातोश्च युक्। गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च। 'वक्ष्यन्ती वेदा गनीगन्ति कर्णम्'।

३५९७। ससूवेति निगमे। ७।४।७४। सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते। 'गृष्टिः ससूव स्थविरम्'। सुषुव इति भाषायाम्।

३५९८। बहुलं छन्दसि। ७।४।७८। अभ्यासस्येकारः स्याच्छन्दसि। 'पूर्णा विवष्टि'। विशेरेतद्रूपम्।

इति सप्तमोऽध्यायः।

३५९९ । प्रसमुपोदः पादपूरणे । ८ । १ । ६ । एषां द्वे स्तः पादपूरणे । 'प्रप्रायमग्निः'। 'संसमिद्युवसे' । 'उपोप मे परामृश' । 'किं नोदुदु हर्षसे' ।

३६०० । छन्दसीरः । ८ । २ । १५ । इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । 'हरिवते हर्यश्वाय' । गीर्वान् ।

३६०१ । अनो नुट् । ८ । २ । १६ । अन्नन्तान्मतोर्नुट् स्यात् । 'अक्षण्वतः कर्णवन्तः'। 'अस्थन्वन्तं यदनस्था बिभर्ति' ।

३६०२ । नाद्धस्य । ८ । २ । १७ । नान्तात्परस्य घस्य नुट् । 'सुपथिन्तरः' । 'भूरिदाव्नस्तुड्वाच्यः' (वा ४७९६) । 'भूरिदावत्तरो जनः' । 'ईद्रथिनः' (वा ४७९९) । 'रथीतरः'। 'रथीतमं रथीनाम्' ।

३६०३ । नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि च्छन्दसि । ८ । २ । ६१ । सदेर्नञ्पूर्वान्निपूर्वाच्च निष्ठाया नत्वाभावो निपात्यते । 'नसत्तमञ्जसा' । 'निषत्तमस्य चरतः' । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः । तूर्वीत्यस्य वा । सूर्तमिति 'सृ' इत्यस्य । गूर्तमिति 'गूरी' इत्यस्य ।

३६०४ । अम्नरूधरवरित्युभयथा छन्दसि । ८ । २ । ७० । रुर्वा रेफो वा । अम्न एव-अम्नरेव । ऊध एव-ऊधरेव । अव एव-अवरेव ।

३६०५ । भुवश्च महाव्याहृतेः । ८ । २ । ७१ । भुव इति-भुवरिति ।

३६०६ । ओमभ्यादाने । ८ । २ । ८७ । ओंशब्दस्य प्लुतः स्यादारम्भे । 'ओ३म् अग्निमीळे पुरोहितम्' । 'अभ्यादाने' किम् । 'ओमित्येकाक्षरं ब्रह्म' ।

३६०७ । ये यज्ञकर्मणि । ८ । २ । ८८ । ये३यजामहे । 'यज्ञ—' इति किम् । ये यजामहे ।

३६०८ । प्रणवष्टेः । ८ । २ । ८९ । यज्ञकर्मणि टेरोमित्यादेशः स्यात् । 'अपां रेतांसि जिन्वतो३म्' । 'टेः' किम् । हलन्तेऽन्त्यस्य मा भूत् ।

३६०९ । याज्यान्तः । ८ । २ । ९० । ये याज्यान्ता मन्त्रास्तेषामन्त्यस्य टेः प्लुतो यज्ञकर्माणि । 'जिह्वामग्ने चकृषे हव्यवाहा३म्' । 'अन्तः' किम् । 'याज्यानामृचां वाक्यसमुदायरूपाणां प्रति वाक्यं टेः स्यात् । सर्वान्त्यस्य चेष्यते ।

३६१० । ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः । ८ । २ । ९१ । एषामादेः प्लुतो यज्ञकर्मणि । 'अग्नयेऽनुब्रू३हि' । 'अग्नये गोमयानि प्रे३ष्य' । 'अस्तुश्रौ३षट्' । 'सोमस्याग्ने वीहि वौ३षट्' । 'अग्निमा३वह' ।

३६११ । अग्नीत्प्रेषणे परस्य च । ८ । २ । ९२ । अग्नीधः प्रेषण आदेः प्लुतस्तस्मात्परस्य च । 'ओ३श्रा३वय' । नेह । 'अग्नीदग्नीन्विहर' । 'वर्हिस्तृणीहि' ।

३६१२ । विभाषा पृष्टप्रतिवचने हेः । ८ । २ । ९३ । प्लुतः । अकार्षीः कटम् । अकार्षं ही३ । अकार्षं हि । 'पृष्ट—' इति किम् । 'कटं करिष्यति हि' । 'हेः' किम् । करोमि ननु ।

३६१३ । निगृह्यानुयोगे च । ८ । २ । ९४ । अत्र यद्वाक्यं तस्य टेः प्लुतो वा । 'अद्यामावास्येत्यात्थ३' । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुप्रयुज्यते ।

३६१४ । आम्रेडितं भर्त्सने । ८ । २ । ९५ । 'दस्योदस्यो३ घातयिष्यामि त्वाम्' । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । 'चौर चौर३' ।

३६१५ । अङ्गयुक्तं तिङाकाङ्क्षम् । ८ । २ ९६ । अङ्गेत्यनेन युक्तं तिङन्तम् प्लुवते । 'अङ्ग कूज३ इदानीं ज्ञास्यसि जाल्म' । 'तिङ्' किम् । 'अङ्ग देवदत्त मिथ्या वदसि' ।'आकाङ्क्षम्' किम् । 'अङ्ग पत्र' । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव ।'अङ्गाधीष्व भक्तं तव दास्यामि' ।

३६१६ । विचार्यमाणानाम् । ८ । २ । ९७ । वाक्यानां टेः प्लुतः । 'होतव्यं दीक्षितस्य गृहा३इ' । 'न होतव्य३मिति' । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ।

३६१७ । पूर्वं तु भाषायाम् । ८ । २ । ९८ । विचार्यमाणानां पूर्वमेव प्लुवते । 'अहिर्नु३ रज्जुर्नु' । प्रयोगापेक्षत्वं पूर्वत्वम् । इह भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ।

३६१८ । प्रतिश्रवणे च । ८ । २ । ९९ । वाक्यस्य टेः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । 'गां मे देहि भो३' । 'हन्त ते ददामि३' । 'नित्यः शब्दो भवितुमर्हति३' । 'दत्त किमात्थ' ।

३६१९ । अनुदात्तं प्रश्नान्ताभिपूजितयोः । ८ । २ । १०० । अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत३इ । पट३उ । 'अग्निभूते' 'पटो' एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक ३ ।

३६२० । चिदिति चोपमार्थे प्रयुज्यमाने । ८ ।२ ।१०१ । वाक्यस्य टेरनुदात्तः प्लुतः । 'अग्निचिद्भाया३त्' । अग्निरिव भायात् । 'उपमार्थे' किम् । कथंचिदाहुः । 'प्रयुज्यमाने' किम् । अग्निर्माणवको भायात् ।

३६२१ । उपरिस्विदासीदिति च । ८ । २ । १०२ । टेः प्लुतोऽनुदात्तः स्यात् । 'उपरि स्विदासी३ त्' । 'अधःस्विदासी३ त्' इत्यत्र तु 'विचार्यमाणानाम्' (सू ३६१६) इत्युदात्तः प्लुतः ।

३६२२ । स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु । ८ । २ । १०३ । स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । -अभिरूपक३ अभिरूपक रिक्तं त आभिरूप्यम् । संमतौ । अभिरूपक३ अभिरूपक शोभनोऽसि । कोपे । अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक३ शाक्तीक रिक्ता ते शक्तिः ।

३६२३ । क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् । ८ । २ । १०४ । आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यात् । आचारभेदे । स्वयं ह रथेन याति३ । उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्रांश्च लप्सीष्ट३ धनं च तात । व्यापारणे । कटं कुरु३ ग्रामं गच्छ । 'आकाङ्क्षम्' किम् । दीर्घायुरसि अग्नीदग्नीन्विहर ।

३६२४ । अनन्त्यस्यापि प्रश्नाख्यानयोः । ८ । २ । १०५ । अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः । प्रश्ने । अगम३ः पूर्वा३ न्ग्रामा३ न् । सर्वपदानामयम् । आख्याने । अगम३ म् पूर्वा३ न्ग्रामा३ न् ।

३६२५ । प्लुतावैच इदुतौ । ८ । २ ।१०६ । दूराद्धूतादिषु प्लुतो विहितस्तत्रैवैचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लुवेते । ऐ ४ तिकायन । औ४ पगव । चतुर्मात्रावत्रैचौ संपद्येते ।

३६२६ । एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ । ८ । २ । १०७ ।

अप्रगृह्यस्यैचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः। 'प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव' ।(वा ४८८८) प्रश्नान्ते । अगमः३ पूर्वा ३ न्ग्रामा३ न् । अग्निभूत इ । अभिपूजिते । भद्रं करोषि पट३ उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृहा३इ । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत३इ । याज्यान्ते । स्तोमैर्विधेमाग्नय३इ । 'परिगणनम्' किम् । विष्णुभूते३ घातयिष्यामि त्वाम् । अदूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह मा भूत् । भद्रं करोषि गौरिति । 'अप्रगृह्यस्य' किम् । शोभने मालेः३ । 'आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः' । (वा ४८८९) अग्ना३ इ पत्नी वः ।

३६२७ । तयोर्य्वावचि संहितायाम् । ८ । २ । १०८ । इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न३याशा । पट३वाशा । अग्न३ यिन्द्रम् । पट३ वुदकम् । 'अचि' किम् । अग्ना ३ वरुणौ । 'संहितायाम्' किम् । अग्न३इ इन्द्रः । संहितायामित्यध्यायसमाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्णदीर्घत्वस्य शाकलस्य च निवृत्त्यर्थः । यवयोरसिद्धत्वात् 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (सू ३६५७ इत्यस्य बाधनार्थो वा ।

३६२८ । मतुवसो रु संबुद्धौ छन्दसि । ८ । ३ । १ । रु इत्यविभक्तिको निर्देशः । मत्वन्तस्य वस्वन्तस्य च रुः स्यात् । 'अलोऽन्त्यस्य' (सू ४२) इति परिभाषया नकारस्य । 'इन्द्र मरुत्व इह पाहि सोमम्' । 'हरिवो मे दिनं त्वा' । 'छन्दसीरः' (सू ३६००)इति वत्वम्।

३६२९ । श्वान्साह्वान्मीढ्वांश्च । ६ । १ । १२ । एते क्वस्वन्ता निपात्यन्ते । 'मीढ्वस्तोकाय तनयाय' । 'वन उपसंख्यानम्' (वा ४८९०) । क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । 'यस्त्वायन्तं वसुना प्रातरित्वः' । इणः क्वनिप् ।

३६३० । उभयथर्क्षु । ८ । ३ । ८ । । अम्परे छवि नकारस्य रुर्वा । पशूंस्तांश्चक्रे ।

३६३१ । दीर्घादटि समानपादे । ८ । ३ । ९ । दीर्घान्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् । 'देवाँ अच्छा सुमती' । 'महाँ इन्द्रो य ओजसा' । उभयथेत्यनुवृत्तेर्नेह । 'आदित्यान्याचिषामहे' ।

३६३२ । आतोऽटि नित्यम् । ८ । ३ । ३ । अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । 'महाँ इन्द्रः' । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ।

३६३३ । स्वतवान्पायौ । ८ । ३ । ११ । रुर्वा । 'भुवस्तस्य स्वतवाँ पायुरग्ने' ।

३६३४ । छन्दसि वाप्राम्रेडितयोः । ८ । ३ । ४९ । विसर्गस्य सो वा स्यात्कुप्वोः प्रशब्दमाम्रेडितं च वर्जयित्वा । 'अग्ने त्रातर्ऋतस्कविः' । 'गिरिर्न विश्वतस्पृथुः' । नेह । 'वसुनः पूर्व्यः पतिः' । 'अप्र-' इत्यादि किम् । 'अग्निः प्र विद्वान्' । 'पुरुषःपुरुषः' ।

३६३५ । कःकरत्करतिकृधिकृतेष्वनदितेः । ८ । ३ । ५० । विसर्गस्य सः स्यात् । 'प्रदिवो अपस्कः' । 'यथा नो वस्यसस्करत्' । 'सुपे शस्करति' । 'उरुणस्कृधि' । 'सोमं न चारुं मघवत्सु नस्कृतम्' । 'अनदितेः' इति किम् । 'यथा नो अदितिः करत्' ।

३६३६ । पञ्चम्याः परावध्यर्थे । ८ । ३ । ५१ पञ्चमीविसर्गस्य सः स्यादुपरिभावार्थे परिशब्दे परतः । 'दिवस्परिप्रथमं जज्ञे' । 'अध्यर्थे' किम् । 'दिवस्पृथिव्याः पर्योजः' ।

३६३७ । पातौ च बहुलम् । ८ । ३ । ५२ । पञ्चम्या इत्येव । 'सूर्यो नो दिवस्पातु' ।

३६३८ । षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु । ८ । ३ । ५३ । 'वाचस्पतिं विश्वकर्माणम्' । 'दिवस्पुत्राय सूर्याय' । 'दिवस्पृष्ठं भन्दमानः' । 'तमसस्पारमस्य' । 'परिवीत इलस्पदे' । 'दिवस्पयो दिधिषाणाः' । रायस्पोषं यजमानेषु' ।

३६३९ । इडाया वा । ८ । ३ ५४ । पतिपुत्रादिषु परेषु । इळायास्पुत्रः–इळायाः पुत्रः । इळायास्पदे–इळायाःपदे । 'निसस्तपतावनासेवने' (सू २४०३) । निसः सकारस्य मूर्धन्यः स्यात् । 'निष्टप्तं रक्षो निष्टप्ता अरातयः' । 'अनासेवने' किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ।

३६४० । युष्मत्तत्ततक्षुःष्वन्तःपादम् । ८ । ३ । १०३ । पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेनवाः । 'त्रिभिष्ट्वं देव सवितः' । 'तेभिष्ट्वा अभिष्टे' । 'अप्स्वग्ने सधिष्टव' । 'अग्निष्टद्विश्वम्' । 'द्यावापृथिवी निष्टतक्षुः' । 'अन्तःपादम्' किम् । 'तदग्निस्तदर्यमा' । 'यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहाजातवेदा विचर्षणिः' । अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः ।

३६४१ । यजुष्येकेषाम् । ८ । ३ । १०४ । युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्ष आर्चिभिस्त्वमित्यादि ।

३६४२ । स्तुतस्तोमयोश्छन्दसि । ८ । ३ । १०५ । नृभिष्टुतस्य–नृभिः स्तुतस्य । गोष्टोमम्–गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ।

३६४३ । पूर्वपदात् । ८ । ३ । १०६ । पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । 'यदिन्द्राग्नी दिवि ष्ठः' । 'युवं हि स्थः स्वर्पती' ।

३६४४ । सुञः । ८ । ३ । १०७ । पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । 'ऊर्ध्व ऊ षु णः' । 'अभी षु णः' ।

३६४५ । सनोतेरनः । ८ । ३ । १०८ । 'गोषा इन्दो नृषा असि' । 'अनः' किम् । गोसनिः ।

३६४६ । सहेः पृतनर्ताभ्यां च । ८ । ३ । १०९ । पृतनाषाहम् । ऋताषाहम् । चात् । ऋतीषाहम् ।

३६४७ । निव्यभिभ्योऽड्व्यवाये वा छन्दसि । ८ । ३ । ११९ । सस्य मूर्धन्यः । न्यषीदत्–न्यसीदत् । व्यषीदत्–व्यसीदत् । अभ्यष्टौत्–अभ्यस्तौत् ।

३६४८ । छन्दस्यृदवग्रहात् । ८ । ४ । २६ । ऋकारान्तादवग्रहात्परस्य नस्य णः नृमणाः । पितृयाणम् ।

३६४९ । नश्च धातुस्थोरुषुभ्यः । ८ । ४ २७ । धातुस्थात् । 'अग्ने रक्षा णः' । 'शिक्षा णो अस्मिन्' । 'उरु णस्कृधि' । 'अभी षु णः' । 'मो षु णः' ।

इत्यष्टमोऽध्यायः

इति वैदिकप्रकरणम् ।

अथ स्वरप्रकरणम् ।

३६५० । अनुदात्तं पदमेकवर्जम् । ६ । १ । १५८ । परिभाषेयम् । स्वरविधिविषया। यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्तच्कं स्यात् । 'गोपायतं नः' । अत्र 'सनाद्यन्ताः–' (सू २३०४) इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् । 'सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम्' । (वा ३७३०) तेनोक्तोदाहरणे । गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । 'अन्यत्र' इति किम् । 'यज्ञं यज्ञमभिवृद्धे गृणीतः' । अत्र सति शिष्टोऽपि 'श्ना' इत्यत्र स्वरो। शिष्यते किंतु तस एव ।

३६५१ । अनुदात्तस्य च यत्रोदात्तलोपः । ६ । १ । १६१ । यस्मिन्ननुदात्ते पर उदात्तो लुप्यते तस्योदात्तः स्यात् । 'देवीं वाचम्' । अत्र ङीबुदात्तः ।

३६५२ । चौ । ६ । १ । २२२ । लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । 'देवद्रीचीं नयत देवयन्तः' । 'अतद्धित इति वाच्यम्' (वा ३७८९)। दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ।

३६५३ । आमन्त्रितस्य च । ६ । १ । १९८ । आमन्त्रितविभक्त्यन्तस्यादिरुदात्तः स्यात् । 'अग्न इन्द्र वरुण मित्र देवाः' ।

३६५४ । आमन्त्रितस्य च । ८ । १ । १९ । पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्टमिकः । 'इमं मे गङ्गे यमुने सरस्वति' । 'अपादादौ' किम् । 'शुतुद्रि स्तोमम्' । 'आमन्त्रितं पूर्वमविद्यमानवत्' (सू ४१२) । 'अग्न इन्द्र' । अत्रेन्द्रादीनां निघातो न । पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् । 'नामन्त्रिते समानाधिकरणे सामान्यवचनम्' (सू ४१३) । समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । 'अग्ने तेजस्विन्' । 'अग्ने त्रातः' । 'सामान्यवचनम्' किम् । पर्यायेषु मा भूत् । 'अघ्न्ये देवि सरस्वति' ।

३६५५ । सामान्यवचनं विभाषितं विशेषवचने । ८ । १ । ७४ । अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । 'देवीः षलुर्वीरुरु नः कृणोत' । अत्र देवीनां विशेषणं षडिति । 'देवाः शरण्याः' । इह द्वितीयस्य निघातो वैकल्पिकः ।

३६५६ । सुबामन्त्रिते पराङ्गवत्स्वरे । २ । १ । २ । सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्यात्स्वरे कर्तव्ये । 'द्रवत्पाणी शुभस्पती' । शुभ इति शुभेः क्विबन्तषष्ठ्यन्तम् । तस्य परशरीरानुप्रवेशे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघातः शङ्क्यः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । 'यत्ते दिवो दुहितर्मर्तभोजनम्' । इह दिवःशब्दस्याष्टमिको निघातः । 'परशुना वृश्चन्' । 'षष्ठ्यामन्त्रितकारकवचनम्' (वा १२२३) । षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनेह न । 'अयमग्ने जरिता' । 'एतेनाग्ने ब्रह्मणा' । समर्थानुवृत्त्या वा सिद्धम् । 'पूर्वाङ्गवच्चेति वक्तव्यम्' (वा १२२८)। आ ते पितर्मरुताम् । 'प्रति त्वा दुहितर्दिवः' । 'अव्ययानां न' (वा १२२९)। 'उच्चैरधीयान' । 'अनव्ययीभावस्य त्विष्यते' । (वा १२३०) 'उपाग्न्यधीयान' ।

३६५७। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य। ८। २। ४। उदात्तस्थाने स्वरितस्थाने च यो यण्ततः परस्यानुदात्तस्य स्वरितः स्यात्। अभ्यभि हि। स्वरितस्य यणः। खलङ्थाशा। अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न।

३६५८। एकादेश उदात्तेनोदात्तः। ८। २। ५। उदात्तेन सहैकादेश उदात्तः स्यात्। 'वोऽश्वाः'। 'क्वावरं मरुतः'।

३६५९। स्वरितो वानुदात्ते पदादौ। ८। २। ६। अनुदात्ते पदादौ पर उदात्तेन सहैकादेशः स्वरितो वा स्यात्। पक्षे पूर्वसूत्रेणोदात्तः। 'वीऽइदं ज्योतिर्हृदये'। 'अस्य श्लोको दिवीयते'। व्यवस्थितविभाषात्वादिकारयोः स्वरितः। दीर्घप्रवेशे तूदात्तः। किं च 'एङः पदान्तात्–' (सू ८६)। इति पूर्वरूपे स्वरित एव। तेऽवदन्। 'सोऽयमागात्'। उक्तं च प्रातिशाख्ये–'इकारयोश्च प्रश्लेषे क्षैप्राभिनिहतेषु च' इति।

३६६०। उदात्तादनुदात्तस्य स्वरितः। ८। ४। ६६। उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात्। 'अग्निमीळे'। अस्याप्यसिद्धत्वाच्छेषनिघातो न। 'तमीशानासः'।

३६६१। नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्। ८। ४। ६७। उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात्। गार्ग्यादिमते तु स्यादेव। 'प्र य आरुः'। 'वोऽश्वाः'। क्वा३भीशवः'।

३६६२। एकश्रुति दूरात्संबुद्धौ। १। २। ३३। दूरात्संबोधने वाक्यमेकश्रुतिः स्यात्। त्रैस्वर्यापवादः। 'आगच्छ भो माणवक'।

३६६३। यज्ञकर्मण्यजपन्यूङ्खसामसु। १। २। ३४। यज्ञक्रियायां च एकश्रुति स्याज्जपादीन्वर्जयित्वा। 'अग्निर्मूर्धा दिवः ककुत्'। 'यज्ञ–' इति किम्। स्वाध्यायकाले त्रैस्वर्यमेव। 'अजप–' इति किम्। 'ममाग्ने वर्चो विहवेष्वस्तु'। जपो नाम उपांशुप्रयोगः। यथा जले निमग्नस्य। न्यूङ्खा नाम षोडश ओकाराः। गीतिषु सामाख्या।

३६६४। उच्चैस्तरां वा वषट्कारः। १। २। ३५। यज्ञकर्मणि वौषट्छब्द उच्चैस्तरां वा स्यादेकश्रुतिर्वा।

३६६५। विभाषा छन्दसि। १। २। ३६। छन्दसि विभाषा एकश्रुतिः स्यात्। व्यवस्थितविभाषेयं। संहितायां त्रैस्वर्यम्। ब्राह्मण एकश्रुतिर्बह्वृचानाम्। अन्येषामपि यथासंप्रदायं व्यवस्था।

३६६६। न सुब्रह्मण्यायां स्वरितस्य तूदात्तः। १। २। ३७। सुब्रह्मण्याख्ये निगदे 'यज्ञकर्मणि–' (सू ३६६३) इति 'विभाषा छन्दसि' (सू ३६३५) इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्योदात्तश्च स्यात्। सुब्रह्मण्योम्। सुब्रह्मणि साधुरिति यत्। न च 'एकादेश उदात्तेनोदात्तः' (सू ३६५८) इति सिद्धे पुनरनेनेदमुदात्तविधानं व्यर्थमिति वाच्यम्। तत्रानुदात्त इत्यस्यानुवृत्तेः। 'असावित्यन्तः' (वा ६५१)। तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्त स्यात्। गार्ग्यो यजते। ञित्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते। 'अमुष्येत्यन्तः' (वा ६५२)। षष्ठ्यन्तस्यापि प्राग्वत्। दाक्षेः पिता यजते। 'स्यान्तस्योपोत्तमं च' (वा ६५३)। चादन्तः। तेन द्वावुदात्तौ। गार्ग्यस्य पिता यजते। 'वा नामधेयस्य' (वा ६५४)। स्यान्तस्य नामधेयस्य उपोत्तममुपात्तं वा स्यात्। देवदत्तस्य पिता यजते।

३६६७। देवब्रह्मणोरनुदात्तः । १ । २ । ३८ । अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । 'देवा ब्राह्मण आगच्छत' ।

३६६८। स्वरितात्संहितायामनुदात्तानाम् । १ । २ । ३९ । स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् । 'इमं मे गङ्गे यमुने सरस्वति' ।

३६६९। उदात्तस्वरितपरस्य सन्नतरः । १ । २ । ४० । उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तनतरः स्यात् । 'सरस्वति शुतुद्रि' । 'व्यचक्षयत्स्वः' । 'तस्य परमाम्रेडितम्' (सू ८३)।

३६७०। अनुदात्तं च । ८ । १ । ३ । द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । 'दिवेदिवे'।

इति साधारणस्वराः ।

३६७१। धातोः । ६ । १ । १६२ । अन्त उदात्तः स्यात् । 'गोपायतं नः' । 'असि सत्यः' ।

३६७२। स्वपादिर्हिंसामच्यनिटि । ६ । १ । १८८ । स्वपादीनां हिंसेश्चानिटयजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्तता । 'क्लिन्द्रयेवेध्यते' । नेह । स्वपानि । हिनसानि ।

३६७३। अभ्यस्तानामादिः । ६ । १ । १८९ । अनिटयजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । 'ये ददति प्रिया वसु' । परत्वाच्चित्स्वरमयं बाधते । 'दधाना इन्द्रे' ।

३६७४। अनुदात्ते च । ६ । १ । १९० । अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । 'दधासि रत्नं द्रविणं च दाशुषे' ।

३६७५। भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति । ६ । १ । १९२। भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । 'योऽग्निहोत्रं जुहोति' । 'ममत्तु नः परिज्मा' । 'माता यद्वीरं दधनत्' । 'जागर्षि त्वम्' ।

३६७६। लिति । ६ । १ । १९३ । प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ।

३६७७। आदिर्णमुल्यन्यतरस्याम् । ६ । १ । १९४ । अभ्यस्तानामादिरुदात्तो वा णमुलि परे । लोलूयं लोलूयम् । पक्षे लित्स्वरः ।

३६७८। अचः कर्तृयकि । ६ । १ । १९५ । उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ।

३६७९। चङ्यन्यतरस्याम् । ६ । १ । २१८ । चङन्ते धातावुपोत्तममुदात्तं वा । 'मा हि चीकरताम्' । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ।

इति धातुस्वराः ।

३६८०। कर्षात्वतो घञोऽन्त उदात्तः । ६ । १ । १५९ । कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः । पाकः ।

३६८१। उञ्छादीनां च । ६ । १ । १६० । अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । 'वैश्वानरः कुशिकेभिर्युगेयुगे'।

---

१ नैतद्भाष्ये दृष्टम्-इति शेखरकृत् ।

अन्यत्र 'योगे योगे तवस्तरम्' । भक्षशब्दो घञन्तः । 'गावः सोमस्य प्रथमस्य भक्षः' । उत्तमशश्वत्तमावपि । 'उदुत्तमं वरुण' । 'शश्वत्तममीळते' ।

३६८२ । चतुरः शसि । ६ । १ । १६७ । चतुरोऽन्त उदात्तः शसि परे । 'चतुरः कल्पयन्तः' । 'अचिरः—' (सू. २९९) इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य 'चतेरुरन्' । नित्त्वादाद्युदात्तता ।

३६८३ । झल्युपोत्तमम् । ६ । १ । १८७ । षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पद उपोत्तममुदात्तं स्यात् । 'अध्वर्युभिः पञ्चभिः' । 'नवभिर्वाजैर्नवती च' । 'सनभ्यो जायमानः' । 'आ दशभिर्विवस्वतः' । 'उपोत्तमम्' किम् । 'आ षड्भिर्हूयमानः' । 'विश्वे देवैस्त्रिभिः' 'झलि' किम् । 'नवानां नवतीनाम्' ।

३६८४ । विभाषा भाषायाम् । ६ । १ । १८१ । उक्तविषये ।

३६८५ । सर्वस्य सुपि । ६ । १ । १९१ । सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । 'सर्वे नन्दन्ति यशसा' ।

३६८६ । ञ्नित्यादिर्नित्यम् । ६ । १ । १९७ । ञिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् । 'यस्मिन्विश्वानि पौंस्या' । पुंसः कर्मणि ब्राह्मणादित्वात्ष्यञ् । 'सुतेदधिष्व नश्चनः' । चायतेरसुन् । 'चायेरन्ने ह्रस्वश्च' (उणा) इति चकारादसुनो नुडागमश्च ।

३६८७ । पथिमथोः सर्वनामस्थाने । ६ । १ । १९९ । आदिरुदात्तः स्यात् । अयं पन्थाः । 'सर्वनामस्थाने' किम् । 'ज्योतिष्मतः पथो रक्ष' । उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् ।

३६८८ । अन्तश्च तवै युगपत् । ६ । १ । २०० । तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । 'हर्षसे दातवा उ' ।

३६८९ । क्षयो निवासे । ६ । १ । २०३ । आद्युदात्तः स्यात् । 'स्वे क्षये शुचिव्रत' एरजन्तः ।

३६९० । जयः करणम् । ६ । १ । २०२ । करणवाची जयशब्द आद्युदात्तः स्यात् जयत्यनेन जयोऽश्वः ।

३६९१ । वृषादीनां च । ६ । १ । २०३ । आदिरुदात्तः । आकृतिगणोऽयम् । 'वाजेभिर्वाजिनीवती' । 'इन्द्रं वाणीः' ।

३६९२ । संज्ञायामुपमानम् । ६ । १ । २०४ । उपमानशब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा । कनोऽत्र लुप् । एतदेव ज्ञापयति 'क्वचित्स्वरविधौ प्रत्ययलक्षणं न' इति । 'संज्ञायाम्' किम् । अग्निर्माणवकः । 'उपमानम्' किम् । चैत्रः ।

३६९३ । निष्ठा च द्व्यजनात् । ६ । १ । २०५ । निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । 'द्व्यचः' किम् । चिन्तितः । 'अनात्' किम् । त्रातः । 'संज्ञायाम्' इत्यनुवृत्तेर्नेह । कृतम् । हृतम् ।

३६९४ । शुष्कधृष्टौ । ६ । १ । २०६ । एतावाद्युदात्तौ स्तः । असंज्ञार्थमिदम् । 'अतसं न शुष्कम्' ।

३६९५ । आशितः कर्ता । ६ । १ । २०७ । कर्तृवाच्याशितशब्द आद्युदात्तः । 'कृषाश्नित्फाल आशितम्' ।

३६९६ । रिक्ते विभाषा । ६ । १ । २०८ । रिक्तशब्दे वादिरुदात्तः । रिक्तः । संज्ञायां तु 'निष्ठा च द्व्यजनात्' (सू ३६९३) इति नित्यमाद्युदात्तत्वं पूर्वविप्रतिषेधेन ।

३६९७ । जुष्टार्पिते च च्छन्दसि । ६ । १ । २०९ । आद्युदात्ते वा स्तः ।

३६९८ । नित्यं मन्त्रे । ६ । १ । २१० । एतत्सूत्रं शक्यमकर्तुम् । 'जुष्टो दमूनाः' 'पलं आहुरर्पितम्' इत्यादेः पूर्वेणैव सिद्धेः छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । 'अर्पिताः षष्टिर्न चलाचलासः' इत्यत्रान्तोदात्तदर्शनाच्च ।

३६९९ । युष्मदस्मदोर्ङसि । ६ । १ । २११ । आदिरुदात्तः स्यात् । 'न हि षस्तव नो मम' ।

३७०० । ङयि च । ६ । १ । २१२ । 'तुभ्यं हिन्वानः' । 'मह्यं वातः पवताम्' ।

३७०१ । यतोऽनावः । ६ । १ । २१३ । यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तः, नावं विना 'युञ्जन्त्यस्य काम्या' । कमेर्णिङन्तादचो यत् । 'अनावः' किम् । 'नवतिं नाव्यानाम्' ।

३७०२ । ईडवन्दवृशंसदुहां ण्यतः । ६ । १ । २१४ । एषां ण्यदन्तानामादिरुदात्तः । 'ईड्यो नूतनैरुत' । आजुह्वान ईड्यो वन्द्यश्च' । 'श्रेष्ठं नो धेहि वार्यम्' । 'उक्थमिन्द्राय शंस्यम्' ।

३७०३ । विभाषा वेण्विन्धानयोः । ६ । १ । २१५ । आदिरुदात्तो वा । 'इन्धानो अग्निम्' ।

३७०४ । त्यागरागहासकुहश्वठक्रथानाम् । ६ । १ । २१६ । आदिरुदात्तो वा । आद्यास्त्रयो घञन्ताः । त्रयः पचाद्यजन्ताः ।

३७०५ । मतोः पूर्वमात्संज्ञायां स्त्रियाम् । ६ । १ । २१९ । मतोः पूर्वमाकार उदात्तः स्त्रीनाम्नि । उदुम्बरावती । शरावती ।

३७०६ । अन्तोऽवत्याः । ६ । १ । २२० । अवतीशब्दस्यान्त उदात्तः । वेत्रवती । ङीपः पित्त्वादनुदात्तत्वं प्राप्तम् ।

३७०७ । ईवत्याः । ६ । १ । २२१ । ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ।

अथ फिट्सूत्राणि ।

१ 'फिषोऽन्त उदात्तः' । प्रातिपदिकं फिट् । तस्यान्त उदात्तः स्यात् । उच्चैः । २ 'पाटलापालङ्काम्बासागरार्थानाम्' । एतदर्थानामन्त उदात्तः । 'पाटला' 'फलेरुहा' 'सुरूपा' 'पाकला' इति पर्यायाः । 'लघावन्ते-' इति प्राप्ते । 'अपालङ्क' 'व्याधिघात' 'आरेवत' 'आरग्वध' इति पर्यायाः । अम्बार्थः । माता । 'उनर्वन्नन्तानाम्' इत्याद्युदात्तत्वे प्राप्ते । सागरः । समुद्रः । ३ 'गेहार्थानामस्त्रियाम्' । गेहम् । 'नब्विषयस्य-' इति प्राप्ते । 'अस्त्रियाम्' किम् । शाला । आद्युदात्तोऽयम् । इहैव पर्युदासाज्ज्ञापकात् । ४ 'गुदस्य च' । अन्त उदात्तः स्यान्न तु स्त्रियाम् । गुदम् । 'अस्त्रियाम्' किम् । 'आन्त्रेभ्यस्ते गुदाभ्यः' । 'स्वाङ्गशिटामदन्तानाम्' इत्यन्तरङ्गमाद्युदात्तत्वम् । ततष्टाप् । ५ 'ध्यपूर्वस्य स्त्रीविषयस्य' । धकारयकारपूर्वो योऽन्त्योऽच्स उदात्तः । अन्तर्धा । 'स्त्रीविषयवर्ण-' इति प्राप्ते । छाया । माया । जाया । 'यान्तस्यान्त्यात्पूर्वम्' इत्याद्युदात्तत्वे

प्राप्ते । 'स्त्री' इति किम् । वाध्यम् । यञन्तत्वादाद्युदात्तत्वम् । 'विषयग्रहणम्' किम् । इभ्या । क्षत्रिया । 'यतोऽनावः' (सू ३७०१) इत्याद्युदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु 'यान्तस्यान्त्यात्पूर्वम्' इति मध्योदात्तः । ६ 'खान्तस्याश्मादेः' । नखम् । उखा । सुखम् । दुःखं । नखस्य 'स्वाङ्गशिटाम्–' इत्याद्युदात्तत्वे प्राप्ते । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात् 'खय्युवर्णं कृत्रिमाख्या चेत्' इत्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुःखयोः 'नब्विषयस्य–' इति प्राप्ते । 'अश्मादेः' किम् । शिखा । मुखम् । मुखस्य 'स्वाङ्गशिटाम्–' इति 'नब्विषयस्य–' इति वा आद्युदात्तत्वम् । शिखायास्तु 'शीङः खो निह्रस्वश्च' इत्युणादिषु नित्त्वोक्तेरन्तरङ्गत्वात्प्रागेव 'स्वाङ्गशिटाम्–' इति वा बोध्यम् । ७ 'बंहिष्ठवत्सरतिशत्थान्तानाम्' । एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः । नित्त्वादाद्युदात्तत्वे प्राप्ते । 'बंहिष्ठैरश्वैः सुवृता रथेन' । 'यद्बंहिष्ठं नातिविधे' इत्यादौ व्यत्ययादाद्युदात्तः । संवत्सरः । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । अशीतिः । 'लघावन्ते–' इति प्राप्ते । चत्वारिंशत् । इहापि प्राग्वत् । 'अभ्यूर्णवाना प्रभृथस्यायोः' । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् । ८ 'दक्षिणस्य साधौ' । अन्त उदात्तः स्यात् । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतयां 'स्वाङ्गशिटाम्–' इत्याद्युदात्तः । अर्थान्तरे तु 'लघावन्ते–' इति गुरुरुदात्तः । 'दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु' इति कोशः । ९ 'स्वाङ्गाख्यायामादिर्वा' । इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः । 'आख्याग्रहणम्' किम् । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति । १० 'छन्दसि च' । अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ । ११ 'कृष्णस्यामृगाख्या चेत्' । अन्त उदात्तः । 'वर्णानां तण–' इत्याद्युदात्तत्वे प्राप्ते अन्तोदात्तो विधीयते । कृष्णानां व्रीहीणाम् । 'कृष्णो नो नाव वृषभः' । मृगाख्यायां तु । कृष्णो राज्यै । १२ 'वा नामधेयस्य' । कृष्णस्येत्येव । 'अयं वां कृष्णो अश्विना' । कृष्णर्षिः । १३ 'शुक्लगौरयोरादिः' । नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् । 'सरो गौरो यथापिब' इत्यत्रान्तोदात्तदर्शनात् । १४ 'अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः' । अङ्गुष्ठस्य स्वाङ्गानामकुर्वादीनाम्' इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थं आरम्भः । वशाग्रहणं नियमार्थं छन्दस्येवेति । तेन लोक आद्युदात्तेत्याहुः । १५ 'पृष्ठस्य च' । छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् । पृष्ठम् । १६ 'अर्जुनस्य तृणाख्या चेत्' । 'उनर्वन्नन्तानाम्' इत्याद्युदात्तस्यापवादः । १७ 'आर्यस्य स्वाम्याख्या चेत्' । 'यान्तस्यान्त्यात्पूर्वम्' इति 'यतोऽनावः' (सू ३७०१) इति वाद्युदात्ते प्राप्ते वचनम् । १८ 'आशाया अदिगाख्या चेत्' । दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिक्पर्यायस्याद्युदात्तता । 'इन्द्र आशाभ्यस्परि' । १९ 'नक्षत्राणामाब्विषयाणाम्' । अन्त उदात्तः स्यात् । आश्लेषानुराधादीनां 'लघावन्ते–' इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् । २० 'न कुपूर्वस्य कृत्तिकाख्या चेत्' । अन्त उदात्तो न । कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय 'आर्यिका' 'बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः । २१ 'घृतादीनां च' । अन्त उदात्तः । 'घृतं मिमिक्षे' । आकृतिगणोऽयम् । २२ 'ज्येष्ठकनिष्ठयोर्वयसि' अन्त उदात्तः स्यात् । 'ज्येष्ठ आह चमसा' । 'कनिष्ठ आह चतुरः' । 'वयसि' किम् । ज्येष्ठः श्रेष्ठः । कनिष्ठोऽल्पिकः । इह नित्त्वादाद्यु-

दात्त एव । २३ 'बिल्वतिष्ययोः स्वरितो वा' । अनयोरन्तः स्वरितो वा स्यात् । पक्ष उदात्तः । इति फिट्सूत्रेषु प्रथमः पादः ।

२४ 'अथादिः प्राक् शकटेः' । अधिकारोऽयम् । 'शकटिशकट्योः–' इति यावत् । २५ 'ह्रस्वान्तस्य स्त्रीविषयस्य' । आदिरुदात्तः स्यात् । बलिः । तनुः । २६ 'नब्विषयस्यानिसन्तस्य' । 'वत्रे न वा यः' । इसन्तस्य तु सर्पिः । नब्नपुंसकम् । २७ 'तृणधान्यानां च द्व्यषाम्' । द्व्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्वचां तु गोधूमाः । २८ 'त्रः संख्यायाः' । पञ्च । चत्वारः । २९ 'स्वाङ्गशिटामदन्तानाम्' । शिट् सर्वनाम । 'कर्णाभ्यां छुबुकादधि' । 'ओष्ठाविव मधु' । 'विश्वो विहाय' । ३० 'प्राणिनां कुपूर्वम्' । कवर्गात्पूर्व आदिरुदात्तः । काकः । वृकः । 'शुकेषु मे' । 'प्राणिनाम्' किम् । 'क्षीरं सर्पिर्मधूदकम्' । ३१ 'खय्युवर्णं कृत्रिमाख्या चेत्' । खयि पर उवर्णमुदात्तं स्यात् । कन्दुकः । ३२ 'उनर्वन्नन्तानाम्' । उन । 'वरुणं वो रिशादसम्' । ऋ । 'स्वसारं त्वा कृणवै' । वन् । 'पीवानं मेषम्' । ३३ 'वर्णानां तणतिनितान्तानाम्' । आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित् । ३४ 'ह्रस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये' । ऋद्वर्ज्यं ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् । मुनिः । ३५ 'अक्षस्यादेवनस्य' । आदिरुदात्तः । 'तस्य नाक्षः' । देवने तु । 'अक्षैर्मा दीव्यः' । ३६ 'अर्धस्यासमद्योतने' । अर्धो ग्रामस्य । समेंऽशके तु अर्धं पिप्पल्याः । ३७ 'पीतद्र्वर्थानाम्' । आदिरुदात्तः । पीतद्रुः सरलः । ३८ 'ग्रामादीनां च' । ग्रामः । सोमः । यामः । ३९ 'लुबन्तस्योपमेयनामधेयस्य' । चञ्चेव चञ्चा । 'स्फिगन्तस्य' इति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा । ४० 'न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्' । एषामुपमेयनाम्नामादिरुदात्तो न । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः । ४१ 'राजविशेषस्य यमन्वा चेत्' । यमन्वा वृद्धः । आङ्गमुदाहरणम् । आङ्गाः प्रत्युदाहरणम् । ४२ 'लघावन्ते द्वयोश्च बह्वषो गुरुः' । अन्ते लघौ द्वयोश्च लघ्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः । ४३ 'स्त्रीविषयवर्णाक्षुपूर्वाणाम्' । एषां त्रयाणामाद्युदात्तः । स्त्रीविषयम् । मल्लिका । वर्णः । श्येनी । हरिणी । अक्षुशब्दात्पूर्वोऽस्त्येषां त अक्षुपूर्वाः । तरक्षुः । ४४ 'शकुनीनां च लघु पूर्वम्' । पूर्वं लघु उदात्तं स्यात् । कुक्कुटः । तित्तिरिः । ४५ 'नर्तुप्राण्याख्यायाम्' । यथालक्षणं प्राप्तमुदात्तत्वं न वसन्तः । कृकलासः । ४६ 'धान्यानां च वृद्धक्षान्तानाम्' । आदिरुदात्तः । कान्तानाम् । श्यामाकाः । षान्तानाम् । राजमाषाः । ४७ 'जनपदशब्दानामषान्तानाम्' । आदिरुदात्तः । केकयः । ४८ 'हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा' । हयिति हल्संज्ञा । पललम् । शललम् । 'हयादीनाम्' किम् । एकलः । 'असंयुक्त–' इति किम् । मल्लः । ४९ 'इगन्तानां च द्व्यषाम्' । आदिरुदात्तः । कृषिः । इति फिट्सूत्रेषु द्वितीयः पादः ।

५० 'अथ द्वितीयं प्रागीषात्' । 'ईषान्तस्य हलादेः–' इत्यतः प्राग्द्वितीयाधिकारः । ५१ 'त्र्यचां प्राङ्मकरात्' । 'मकरवरूढ–' इत्यतः प्राक्त्र्यचामित्यधिकारः । ५२ 'स्वाङ्गानामकुर्वादीनाम्' । कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम् । ललाटम् । कुर्वादीनां तु । कपोलः । रसना । वदनम् । ५३ 'मादीनां च' । मलयः । मकरः । ५४ 'शादीनां शाकानाम्' । शीतन्या । शतपुष्पा । ५५ 'पान्तानां गुर्वादीनाम्' । पादपः । आतपः ।

लघ्वादीनां तु । अनूरम् । द्व्यचां तु । नीपम् । ५६ 'युतान्यण्यन्तानाम्' । युत ।
अयुतम् । अनि । धमनिः । अणि । विपणिः । ५७ 'मकरवरूढपारेवतवितस्ते-
क्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा' । एषामादिर्द्वितीयो वोदात्तः । मकरः ।
वरूढ इत्यादि । ५८ 'छन्दसि च' । अमकराद्यर्थं आरम्भः । लक्ष्यानुसारादादिर्द्वितीयं चोदात्तं
ज्ञेयम् । ५९ 'कर्दमादीनां च' । आदिर्द्वितीयं वोदात्तम् । ६० 'सुगन्धितेजनस्य ते वा' ।
आदिर्द्वितीयं तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः । ६१ 'नपः फलान्तानाम्' ।
आदिर्द्वितीयं चोदात्तम् । राजादनफलम् । ६२ 'यान्तस्यान्त्यात्पूर्वम्' । कुलायः । ६३
'थान्तस्य च नालघुनी' । नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा । ६४ 'शिशुमारो-
दुम्बरबलीवर्दोष्ट्रारपुरूरवसां च' । अन्त्यात्पूर्वमुदात्तं द्वितीयं वा । ६५ 'सांकाश्यकाम्पि-
ल्यनासिक्यदार्वाघाटानाम्' । द्वितीयमुदात्तं वा । ६६ 'ईषान्तस्य हयादेरादिर्वा' । हलीषा ।
लाङ्गलीषा । ६७ 'उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्या-
पत्यदेवराणाम्' । एषामादिरुदात्तः स्यात् । ६८ 'महिष्याषाढयोर्जायेष्टकाख्या चेत्' ।
आदिरुदात्तः । महिषी जाया । आषाढा उपदधाति । इति फिट्सूत्रेषु तृतीयः पादः ।

६९ 'शकटिशकट्योरक्षरमक्षरं पर्यायेण' । उदात्तम् । शकटिः-शकटी । ७० 'गोष्ठजस्य
ब्राह्मणनामधेयस्य' अक्षरमक्षरं पर्यायेणोदात्तम् । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः ।
कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । ७१ 'पारावतस्योपोत्तमवर्जम्' । शेषं क्रमेणोदात्तम् ।
पारावतः । ७२ 'धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्' । एषां चतुर्णां
धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः कालवालः । स्थाली-
पाकः । ७३ कपिकेशहरिकेशयोश्छन्दसि' । कपिकेशः । हरिकेशः । ७४ 'न्यङ्स्वरौ स्वरितौ' ।
स्पष्टम् । न्यङ्ङुत्तानः । 'व्यचक्षयत्स्वः' । ७५ 'न्यर्बुदव्यल्कशयोरादिः' । स्वरितः स्यात् । ७६ 'ति-
ल्यशिक्यमर्त्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः' । स्वरितः स्यात् । तिलानां भवनं
क्षेत्रं तिल्यम् । वैश्वानर्या शिक्यमादत्ते । प्रभिन्नायमर्त्यमभ्यास्याति । वज्रः काश्मर्योवज्रेण ।
'यतोनावः' (सू ३७०१) इति प्राप्ते । ७७ 'बिल्वभक्ष्यवीर्याणि छन्दसि' । अन्तस्वरितानि ।
ततोबिल्व उदातिष्ठत् । ७८ 'त्वत्त्वसमसिमेत्यनुच्चानि' । 'स्तरीरु त्वत्' । 'उत त्वः पश्यन्' ।
'नभन्तामन्यके समे' । 'सिमस्मै' । ७९ 'सिमस्याथर्वणेऽन्त उदात्तः' । अथर्वण इति प्रायि-
कम् । तत्र दृष्टस्येत्येवं परं वा । तेन 'वासस्तनुते सिमस्मै' इत्यृग्वेदेऽपि भवत्येव । ८०
'निपाता आद्युदात्ताः' । स्वाहा ८१ 'उपसर्गाश्चाभिवर्जम्' । ८२ 'एवादीनामन्तः' । एवमादी-
नामिति पाठान्तरम् । एव । एवम् । नूनम् । सह । 'सह ते पुत्र सूरिभिः' । षष्ठस्य तृतीये
'सहस्य सः-' (सू १००९) इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः ।
तच्चिन्त्यम् । ८३ 'वाचादीनामुभावुदात्तौ' । उभौग्रहणमनुदात्तं पदमेकवर्जमित्यत्र बा-
धाय । ८४ चादयोऽनुदात्ताः' । स्पष्टम् । ८५ 'यथेति पादान्ते' । 'तं नेमिमृभवो य-
था' । 'पादान्ते' किम् । 'यथा नो अदितिः करत्' । ८६ 'प्रकारादिद्विरुक्तौ' । परस्यान्त
उदात्तः । पटुपटुः । ८७ 'शेषं सर्वमनुदात्तम्' । शेषमित्यादिद्विरुक्तस्य परमित्यर्थः ।
प्रग्रयम् । द्विवेदिं वे । इति फिट्सूत्रेषु तुरीयः पादः ।

३७०८ । आद्युदात्तश्च । ३ । १ । ३ । प्रत्यय आद्युदात्त एव स्यात् । अग्निः । कर्तव्यम् ।

३७०९ । अनुदात्तौ सुप्पितौ । ३ । १ । ४ । पूर्वस्यापवादः । यज्ञस्य । न यो युच्छति शप्तिपोरनुदात्तत्वे स्वरितप्रत्ययौ ।

३७१० । चितः । ६ । १ । १६३ । अन्त उदात्तः स्यात् । 'चितः सप्रकृतेर्बह्वकजर्थम्' (वा ३७४९) चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । 'नर्मन्तामन्यके समे' । 'यके सरस्वतीम्' । 'तकत्सुते' ।

३७११ । तद्धितस्य । ६ । १ । १६४ । चितस्तद्धितस्यान्त उदात्तः । 'पूर्वेण सिद्धे' । जित्स्वरबाधनार्थमिदम् । कौञ्जायनाः ।

३७१२ । कितः । ६ । १ । १६५ । कितस्तद्धितस्यान्त उदात्तः । 'यदाग्नेयः' ।

३७१३ । तिसृभ्यो जसः । ६ । १ । १६६ । अन्त उदात्तः । 'तिस्रो द्यावः सवितुः' ।

३७१४ । सावेकाचस्तृतीयादिर्विभक्तिः । ६ । १ । १६८ । साविति सप्तमीबहुवचनम् । तत्र य एकाच्ततः परा तृतीयादिर्विभक्तिरुदात्ता । 'वाचा विरूपः' । 'सौ' किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य मा भूत् । 'राज्ञो नु ते, । 'एकाचः' किम् । विधते राजनि त्वे' । 'तृतीयादिः' किम् । 'न ददर्श वाचम्' ।

३७१५ । अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे । ६ । १ । १६९ । नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच्ततः परा तृतीयाविभक्तिरन्तोदात्ता वा स्यात् । परमवाचा ।

३७१६ । अञ्चेश्छन्दस्यसर्वनामस्थानम् । ६ । १ । १७० । अञ्चेः परा विभक्तिरुदात्ता । 'इन्द्रो दधीचः' । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तं तृतीयादिरित्यनुवर्तमानेऽसर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । 'प्रतीचो बाहून्' ।

३७१७ । ऊडिदंपदाद्यप्पुम्रैद्युभ्यः । ६ । १ । १७१ । 'ऊठ्' 'इदं' 'पदादि' 'अप्' 'पुम्' 'रै–' 'दिव' इत्येभ्योऽसर्वनामस्थानविभक्तिरुदात्ता ऊठ् । प्रष्ठौहः । प्रष्ठौहा । 'ऊठ्युपधाग्रहणं कर्तव्यम्' (वा ३७५७) । इह मा भूत् । 'अक्षद्युवा' । 'अक्षद्युवे' । इदम् । 'एभिर्नृभिर्नृतमः' । अन्वादेशे न । 'अन्तोदात्तात्' इत्यनुवृत्तेः । न च तत्रान्तोदात्ततात्यस्तीति वाच्यम् । 'इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ' (सू ३५०) इति सूत्रेणानुदात्तस्याशोविधानात् । 'प्र ते बभ्रू' । 'माभ्यां गा अनु' । पद्दन्नोमास्हृन्निश्–' (सू २२८) इति षट् पदादयः । 'पद्भ्यां भूमिः' । 'दद्भिर्न जिह्वा' । 'जायते मासिमासि' । 'मनश्चिन्मे हृद आ' । अप् । 'अपां फेनेन' पुम् । 'अभ्रातेव पुंसः' । रै । 'राया वयम्' । 'रायो धर्ता' । दिव । 'दिवेदिवे' ।

३७१८ । अष्टनो दीर्घात् । ६ । १ । १७२ । शसादिर्विभक्तिरुदात्ता । 'अष्टाभिर्दशभिः' ।

३७१९ । शतुरनुमो नद्यजादी । ६ । १ । १७३ । अनुम्यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नद्यजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । 'अच्छा रवं प्रथमा जानती' । कृण्वते । 'अन्तोदात्तात्' किम् । दधती । 'अभ्यस्तानामादिः' (सू ३६७३) इत्याद्युदात्तः । 'अनुमः' किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुः '–लसार्वधातुकम्–' (सू ३७३०) इति निघातः ।

३७२० । उदात्तयणो हल्पूर्वात् । ६ । १ । १७४ । उदात्तस्थाने यो यण्हल्पूर्वस्तस्मात्परा

नदी शसादिर्विभक्तिश्च उदात्ता स्यात्। 'चोदयित्री सूनृतानाम्'। 'एषां नेत्री'। 'ऋतं देवाय कृण्वते सवित्रे'।

३७२१। नोङ्धात्वोः। ६। १। १७५। अनयोर्यणः परे शसादयं उदात्ता न स्युः। ब्रह्मबन्ध्वा। 'सितृभिः सुभ्वे'।

३७२२। ह्रस्वनुड्भ्यां मतुप्। ६।१।१७६। ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः 'यो अब्दिमाँ उदनिमाँ इयर्ति'। नुटः। 'अक्षण्वन्तः कर्णवन्तः सखायः'। 'अन्तोदात्तात्' किम्। 'मा त्वा विदादिषुमान्'। 'स्वरविधौ व्यञ्जनमविद्यमानवत्' इत्येतदत्र न। 'मरुत्व इन्द्र'। 'नियुत्वांन्वा युवागहि'। 'रैशब्दाच्च' (वा ३७६३) 'रैवाँ इद्रेवतः'।

३७२३। नामन्यतरस्याम्। ६। १। १७७। मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा। 'चेतन्ती सुमतीनाम्'।

३७२४। ङ्याश्छन्दसि बहुलम्। ६। १। १७८। ङ्याः परो नामुदात्तो वा। 'देवसेनानामभिभञ्जतीनाम्'। वेत्युक्तेर्नेह। 'जयन्तीनां मरुतो यन्तु'।

३७२५। षट्त्रिचतुर्भ्यो हलादिः। ६। १। १७९। एभ्यो हलादिर्विभक्तिरुदात्ता। 'आषड्भिर्हूयमानः'। 'त्रिभिष्ट्वं देव'।

३७२६। न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः। ६। १। १८२। एभ्यः प्रागुक्तं न। 'गवां शता'। 'गोभ्यो गातुः'। 'शुनश्चिच्छेपम्'। सौ प्रथमैकवचनेऽवर्णान्तात्। 'तेभ्यो द्युम्नम्'। 'तेषां पाहि श्रुधी हवम्'।

३७२७। दिवो झल्। ६। १। १८३। दिवः परा झलादिर्विभक्तिर्नोदात्ता। 'द्युभिरक्तुभिः'। 'झल्' इति किम्। 'उप त्वाग्ने दिवेदिवे'।

३७२८। नृ चान्यतरस्याम्। ६। १। १८४। नुः परा झलादिर्विभक्तिर्वोदात्ता। 'नृभिर्येमानः'।

३७२९। तित्स्वरितम्। ६। १। १८५। निगदव्याख्यातम्। 'क्व नूनम्'।

३७३०। तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्ह्विङोः। ६। १। १८६। अस्मात्परं लसार्वधातुकमनुदात्तं स्यात्। तासि। कर्ता। कर्तारौ। कर्तारः। प्रत्ययस्वरापवादोऽयम्। अनुदात्तेत्। य आस्ते। ङितः। 'अभि चष्टे अनृतेभिः'। अदुपदेशात्। 'पुरुभुजा चनस्यतम्'। चित्स्वरोऽप्यनेन बाध्यते। 'वर्धमानं स्वे दमे'। 'तास्यादिभ्यः' किम्। 'अभि वधे गृणीतः'। उपदेशग्रहणान्नेह। 'हतो वृत्राण्यार्या'। 'लग्रहणम्' किम्। 'कर्तीह निघ्नानाः'। 'सार्वधातुकम्' किम्। शिश्ये। 'अह्न्विङोः' किम्। ह्नुते। यदधीते। 'विदीन्धिखिदिभ्यो नेतिवक्तव्यम्' (वा ३७४२)। 'इन्धे राजा'। एतच्च 'अनुदात्तस्य च यत्र—' (सू ३६९१) इति सूत्रे भाष्ये स्थितम्।

३७३१। आदिः सिचोऽन्यतरस्याम्। ६। १। १८७। सिजन्तस्यादिरुदात्तो वा 'यासिष्टं वर्तिरश्विना'।

३७३२। थलि च सेटीडन्तो वा। ६। १। १९६। सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात्। यदा नैते त्रयस्तदा 'लिति' (सू ३६७६) इति प्रत्ययात्पूर्वमुदात्तम्। लुलविथ अत्र चत्वारोऽपि पर्यायेणोदात्ताः।

३७३३ । उपोत्तमं रिति । ६ । १ । २१७ । रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । 'यदाहवनीये' ।

इति प्रत्ययस्वराः ।

३७३४ । समासस्य । ६ । १ । २२३ । अन्त उदात्तः स्यात् । 'यज्ञश्रियम्' ।

३७३५ । बहुव्रीहौ प्रकृत्या पूर्वपदम् । ६ । २ । १ । उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् । 'सत्यश्चित्रश्रवस्तमः' । 'उदात्त-' इत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ।

३७३६ । तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः । ६ । २ । २ । सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । 'कृत्यतुल्याख्या अजात्या' (सू ७४९) इति तत्पुरुषः । किरिणा काणः किरिकाणः । 'पतयन्मन्दयत्सखम्' । मन्दयति मादके इन्द्रे सखेति सप्तमीतत्पुरुषः । शस्त्री श्यामा । 'अव्यये नञ्कुनिपातानाम्'(वा ३८०८) । अयज्ञो वा एषः । 'परिगणनम्' किम् । स्नात्वाकालकः । मुहूर्तसुखम् । भोज्योष्णम् ।

३७३७ । वर्णो वर्णेष्वनेते । ६ । २ । ३ । वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्माषः । कृष्णशब्दो नक्प्रत्ययान्तः । लोहितशब्द इतन्नन्तः। 'वर्णः' किम् । परमकृष्णः । 'वर्णेषु' किम् । कृष्णतिलाः । 'अनेते' किम् । कृष्णैतः ।

३७३८ । गाधलवणयोः प्रमाणे । ६ । २ । ४ । एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्गवे दीयते तावदित्यर्थः । अरित्रशब्द इत्रन्नन्तो मध्योदात्तः । प्रमाणमियत्तापरिच्छेदमात्रं न पुनरायाम एव । 'प्रमाणे' किम् । परमगाधम् ।

३७३९ । दायाद्यं दायादे । ६ । २ । ५ । तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः । 'दायाद्यम्' किम् । परमदायादः ।

३७४० । प्रतिबन्धि चिरकृच्छ्रयोः । ६ । २ । ६ । प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते । 'प्रतिबन्धि' किम् । मूत्रकृच्छ्रम् ।

३७४१ । पदेऽपदेशे । ६ । २ । ७ । व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन मूत्रशब्दो घञन्तः उच्चारशब्दो घञन्तः 'थाथ-' (सू ३८७८) आदिस्वरेणान्तोदात्तः । 'अपदेशे' किम् । विष्णुपदम् ।

३७४२ । निवाते वातत्राणे । ६ । २ । ८ । निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीषन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । 'वातत्राणे' किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ।

३७४३ । शारदेऽनार्तवे । ६ । २ । ९ । ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः ।

तत्यास्वपदविग्रहः । 'रज्ज्वोः सद्य उद्धृतम्' । रज्जुशब्दः 'सृजेरसुन्च' (उणा १९) इत्याद्यु-दात्तो व्युत्पादितः । 'अनार्तवे' किम् । उत्तमशारदम् ।

३७४४ । अध्वर्युकषाययोर्जातौ । ६ । २ । १० । एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्मात् 'वैशम्पायनान्तेवासिभ्यश्च' (सू १४८४) इति णिनेः 'कठचरकाल्लुक्' (सू १४८७) । इति लुक् । द्वारि नियुक्त इति ठक्प्रन्तोदात्तो दौवारिकशब्दः । 'जातौ' किम् । परमाध्वर्युः ।

३७४५ । सदृशप्रतिरूपयोः सादृश्ये । ६ । २ । ११ । अनयोः पूर्वं प्रकृत्या । पितृसदृशः । 'सादृश्ये' किम् । परमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ।

३७४६ । द्विगौ प्रमाणे । ६ । २ । १२ । द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्त समाः प्रमाणमस्य । 'प्रमाणे लो द्विगोर्नित्यम्' (वा ३११८-२९) इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । 'द्विगौ' किम् । व्रीहिप्रस्थः । 'प्रमाणे' किम् । परमसप्तसमम् ।

३७४७ । गन्तव्यपण्यं वाणिजे । ६ । २ । १३ । वाणिजशब्दे परे तत्पुरुषे गन्तव्य-वाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । 'गन्तव्य-' इति किम् । परमवाणिजः ।

३७४८ । मात्रोपज्ञोपक्रमच्छाये नपुंसके । ६ । २ । १४ । मात्रादिषु परतो न-पुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो 'गुरोश्च हलः' (सू ३२८०) इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनिशब्द आद्युदात्तः । नन्दोपक्रमम् नन्दशब्दः । पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आद्युदात्तो नित्त्वात् । 'नपुंसके' किम् । कुड्यच्छाया ।

३७४९ । सुखप्रिययोर्हिते । ६ । २ । १५ । एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । 'हिते' किम् । परमसुखम् ।

३७५० । प्रीतौ च । ६ । २ । १६ । प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । 'प्रीतौ' किम् । राजसुखम् ।

३७५१ । स्वं स्वामिनि । ६ । २ । १७ । स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा । गोस्वामी । 'स्वम्' किम् । परमस्वामी ।

३७५२ । पत्यावैश्वर्ये । ६ । २ । १८ । 'दमूना गृहपतिर्दमे' ।

३७५३ । न भूवाक्चिद्दिधिषु । ६ । २ । १९ । पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्पतिः । चित्पतिः । दिधिषूपतिः ।

३७५४ । वा भुवनम् । ६ । २ । २० । उक्तविषये । भुवनपतिः । 'भूसूधूभ्रस्जिभ्यः–' (उणा०) इति क्युन्नन्तो भुवनशब्दः ।

३७५५ । आशङ्काबाधनेदीयस्सु संभावने । ६ । २ । २१ । अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यत आबाध्यते निकटतरमिति वा संभाव्यते । 'संभावने' किम् । परमनेदीयः ।

३७५६ । पूर्वे भूतपूर्वे । ६ । २ । २२ । आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । 'भूतपूर्वे' किम् । परमपूर्वः ।

३७५७ । सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये । ६ । २ । २३ । एषु पूर्वं प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् मद्रसवेशम् । मद्रसदेशम् । 'सामीप्ये' किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ।

३७५८ । विस्पष्टादीनि गुणवचनेषु । ६ । २ । २४ । विस्पष्टकटुकम् । विस्पष्टशब्दो 'गतिरनन्तरः' (सू ३७८३) इत्याद्युदात्तः । 'विस्पष्ट–' इति किम् परमलवणम् । 'गुण–' इति किम् । विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र । व्यक्त । संपन्न । पण्डित । कुशल । चपल । निपुण ।

३७५९ । श्रज्यावमकन्पापवत्सु भावे कर्मधारये । ६ । २ । २५ । 'श्र' 'ज्य' । 'अवम' 'कन्' इत्यादेशवति पापवाचिनि चोत्तरपदे भाववाचि पूर्वपदं प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । 'श्र–' 'इत्यादि' किम् । गमनशोभनम् । 'भावे' किम् । गम्यतेऽनेनेति गमनम् गमनं श्रेयो गमनश्रेयः । 'कर्म–' इति किम् । षष्ठीसमासे मा भूत् ।

३७६० । कुमारश्च । ६ । २ । २६ । कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः ।

३७६१ । आदिः प्रत्येनसि । ६ । २ । २७ । कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ।

३७६२ । पूगेष्वन्यतरस्याम् । ६ । २ । २८ । पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आद्युदात्तत्वाभावे 'कुमारश्च' (सू ३७६०) इत्येव भवति ।

३७६३ । इगन्तकालकपालभगालशरावेषु द्विगौ । ६ । २ । २९ । एषु परेषु पूर्वं प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारत्निः । दशमासान्भूतो दशमास्यः । पञ्चमासान्भूतः । पञ्चमास्यः । 'तमधीष्टो–' (वा १७४४) इत्यधिकारे 'द्विगोर्यप्, (वा १७४६) । पञ्चकपालः पञ्चभगालः । पञ्चशरावः । 'नः संख्यायाः' (फि० २८) इति पञ्चञ्छब्दः । आद्युदात्तः । 'इगन्तादिषु' किम् । पञ्चाश्वः । 'द्विगौ' किम् । परमारत्निः ।

३७६४ । बह्वन्यतरस्याम् । ६ । २ । ३० । बहुशब्दस्तथा वा । बह्वरत्निः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सति 'उदात्तस्वरितयोः–' । (सू ३६५७) इति भवति ।

३७६५ । दिष्टिवितस्त्योश्च । ६ । २ । ३१ । एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ।

३७६६ । सप्तमीसिद्धशुष्कपक्वबन्धेष्वकालात् । ६ । २ । ३२ । अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । सांकाश्यसिद्धः । सांकाश्येति ण्यान्तः । आतपशुष्कः । भ्राष्ट्रपक्वः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः । चक्रशब्दोऽन्तोदात्तः । 'अकालात्' किम् । पूर्वाह्णसिद्धः । कृत्स्वरेण बाधितः सप्तमी स्वरः प्रतिप्रसूयते ।

३७६७ । परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु । ६ । २ । ३३ । एते प्रकृत्या वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्तं वृष्टो देवः । प्रतिपूर्वाह्णम् ।

प्रत्यपरात्रम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । बहुव्रीहितत्पुरुषयोः
सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्यमानार्थत्वात् ।
अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । 'वर्ज्य–' इति किम् । अग्निं प्रति प्रत्यग्नि ।

३७६८ । राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु । ६ । २ । ३४ । राजन्यवाचिनां
बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासु
देवाः शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । 'राजन्य–' इति किम् । द्वैप्यभैमायनाः ।
द्वीपे भवा द्वैप्याः । भैमेरपत्यं युवा भैमायनः । अन्धकवृष्णय एते न तु राजन्याः राजन्यग्रह-
णमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । 'बहुवचनम्' किम् । संकर्ष-
णवासुदेवौ । 'द्वन्द्वे' किम् । वृष्णीनां कुमारा वृष्णिकुमाराः । 'अन्धकवृष्णिषु' किम् ।
कुरुपञ्चालाः ।

३७६९ । संख्या । ६ । २ । ३५ । संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश ।
त्रेस्त्रयसादेश आद्युदात्तो निपात्यते ।

३७७० । आचार्योपसर्जनश्चान्तेवासी । ६ । २ । ३६ । आचार्योपसर्जनान्तेवासिनां
द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहणं
द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवद-
त्तौ । 'आचार्य–' इति किम् । छान्दसवैयाकरणाः । 'अन्तेवासी' किम् । आपिश-
लपाणिनीये शास्त्रे ।

३७७१ । कार्तकौजपादयश्च । ६ । २ । ३७ । एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कार्तकौज-
पौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमाण्डूकेयौ ।

३७७२ । महान्व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु । ६ । २ ।
३८ । महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्णः । महागृष्टिः । महे-
ष्वासः । महाहैलिहिलः । महच्छब्दोऽन्तोदात्तः । 'सन्महत्–' (सू ७४०) इति प्रतिपदोक्तस-
मास एवायं स्वरः । नेह । महतो व्रीहिर्महद्व्रीहिः ।

३७७३ । क्षुल्लकश्च वैश्वदेवे । ६ । २ । ३९ । चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदे-
वम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु कोऽन्तोदात्तः ।

३७७४ । उष्ट्रः सादिवाम्योः । ६ । २ । ४० । उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि
उष्ट्रशब्द आद्युदात्तः ।

३७७५ । गौः सादसादिसारथिषु । ६ । २ । ४१ । गोसादः । गोसादिः । गोसारथिः ।

३७७६ । कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः
पण्यकम्बलो दासीभाराणां च । ६ । २ । ४२ । एषां सप्तानां समासानां दासीभारादेश्च
पूर्वपदं प्रकृत्या । कुरूणां गार्हपतं कुरुगार्हपतम् । उप्रत्ययान्तः कुरुः । 'वृजेरिति
वाच्यम्' (वा ३८१९) । वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः ।
'रिक्ते विभाषा' (सू ३६९६) इति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती ।
अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति
तत् श्लीलम् । सिध्मादित्वाल्लच् । कपिलकादित्वाल्लत्वम् । पारे वडवेव पारेवडवा । निपात-

नादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वेत्यण्णन्तः । पण्यशब्दो यदन्तत्वादाद्युदात्तः । 'पण्यकम्बलः संज्ञायामिति वक्तव्यम्' (वा ३८२०) । अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव । प्रतिपदोक्ते समासे 'कृत्याः' (सू ३८३९) इत्येष स्वरो विहितः । दास्या भारो दासीभारः । देवहूतिः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्य वचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः । 'स राये सपुरन्ध्याम्' । पुरं शरीरं ध्रियतेऽस्यामिति 'कर्मण्यधिकरणे च' (सू ३२७१) इति किप्रत्ययः । अलुक्छान्दसः । 'नब्विषयस्य–' (फिट् २६) इत्याद्युदात्तः पुरशब्दः ।

३७७७ । चतुर्थी तदर्थे । ६ । २ । ४३ । चतुर्थ्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारु यूपदारु ।

३७७८ । अर्थे । ६ । २ । ४४ । अर्थे परे चतुर्थ्यन्तं प्रकृत्या । देवार्थम् ।

३७७९ । क्ते च । ६ । २ । ४५ । क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ।

३७८० । कर्मधारयेऽनिष्ठा । ६ । २ । ४६ । क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । 'कर्मधारये' किम् । श्रेण्या कृतं श्रेणिकृतम् । 'अनिष्ठा' किम् । कृताकृतम् ।

३७८१ । अहीने द्वितीया । ६ । २ । ४७ । अहीनवाचिनि समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । 'अहीने' किम् । कान्तारातीतः । 'अनुपसर्ग इति वक्तव्यम्'(वा ३८२१) । नेह । सुखप्राप्तः । 'थाथ–' (सू ३८७८) इत्यस्यापवादोऽयम् ।

३७८२ । तृतीया कर्मणि । ६ । २ । ४८ । कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । 'त्वोतासः' । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । 'कर्मणि' किम् । रथेन यातो रथयातः ।

३७८३ । गतिरनन्तरः । ६ । २ । ४९ । कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । पुरोहितम् । 'अनन्तरः' किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सातिशिष्टस्थाथादिस्वर एव । दूरादागतः । 'थाथ–' (सू ३८७८) इत्यस्यापवादः ।

३७८४ । तादौ च निति कृत्यतौ । ६ । २ । ५० । तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गतिः प्रकृत्या । 'अग्नेरायो नृतमस्य प्रभूतौ' । 'संगतिं गोः' । कृत्स्वरापवादः । 'तादौ' किम् । प्रजल्पाकः । 'निति' किम् । प्रकर्ता । तृजन्तः । 'अतौ' किम् । आगन्तुः ।

३७८५ । तवै चान्तश्च युगपत् । ६ । २ । ५१ । तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः । प्रकृत्या युगपच्चैतदुभयं स्यात् । 'अन्वेतवा उ' । कृत्स्वरापवादः ।

३७८६ । अनिगन्तोऽञ्चतौ वप्रत्यये । ६ । २ । ५२ । अनिगन्तोगतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । 'ये पराञ्चस्तान्' । 'अनिगन्तः' इति किम् । प्रत्यञ्चो यन्तु । कृत्स्वरात्परत्वादयमेव । 'जहि वृष्ण्यानि कृणुही पराचः' । 'वप्रत्यये' किम् । उदञ्चनम् ।

३७८७ । न्यधी च । ६ । २ । ५३ । वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या ।

न्यङ्कुनानः । 'उदात्तस्वरितयोर्यणः-' (सू ३६५७) इति अन्नतेरकारः । स्वरितः ।
अध्यङ् ।

३७८८ । ईषदन्यतरस्याम् । ६ । २ । ५४ । ईषत्कडारः । ईषदित्ययमन्तोदात्तः । ईषद्भेद इत्यादौ कृत्स्वर एव ।

३७८९ । हिरण्यपरिमाणं धने । ६ । २ । ५५ । सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति । द्विसुवर्णं तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । 'हिरण्यम्' किम् । प्रस्थधनम् । 'परिमाणम्' । किम् । काञ्चनधनम् । 'धने' किम् । निष्कमाला ।

३७९० । प्रथमोऽचिरोपसंपत्तौ । ६ । २ । ५६ । प्रथमशब्दो वा प्रकृत्याभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं । प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । 'अचिर-' इति किम् । प्रथमो वैयाकरणः ।

३७९१ । कतरकतमौ कर्मधारये । ६ । २ । ५७ । वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ।

३७९२ । आर्यो ब्राह्मणकुमारयोः । ६ । २ । ५८ । आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । 'आर्यः' किम् । परमब्राह्मणः । 'ब्राह्मणादि-' इति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ।

३७९३ । राजा च । ६ । २ । ५९ । ब्राह्मणकुमारयोः परतो राजा वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ।

३७९४ । षष्ठी प्रत्येनसि । ६ । २ । ६० । षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या । राजप्रत्येनाः । 'षष्ठी' किम् । अन्यत्र न ।

३७९५ । क्ते नित्यार्थे । ६ । २ । ६१ । क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या । नित्यप्रहसितः । 'कालाः' (सू ६९०) इति द्वितीयासमासोऽयम् । निशब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । 'नित्यार्थे' किम् । मुहूर्तप्रहसितः

३७३६ । ग्रामः शिल्पिनि । ६ । । २ । ६२ । वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आद्युदात्तः । 'ग्रामः' किम् । परमनापितः । 'शिल्पिनि' किम् । ग्रामरथ्या ।

३७९७ । राजा च प्रशंसायाम् । ६ । २ । ६३ । शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । 'प्रशंसायाम्' किम् । राजनापितः । 'शिल्पिनि' किम् । राजहस्ती ।

३७९८ । आदिरुदात्तः ६ । २ । ६४ । अधिकारोऽयम् ।

३७९९ । सप्तमीहारिणौ धर्म्येऽहरणे । ६ । २ । ६५ । सप्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे । देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । 'संज्ञायाम्' (सू ७२१) इति सप्तमीसमासः । 'कारनाम्नि च-, (सू ९६८) इत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । 'धर्म्ये-' इति किम् । स्तम्बेरमः । 'अहरणे' किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेका-

दुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेण बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ।

३८०० । युक्ते च । ६ । २ । ६६ । युक्तवाचिनि समासे पूर्वमाद्युदात्तम् । गोबल्लवः । 'कर्तव्ये तत्परो युक्तः' ।

३८०१ । विभाषाध्यक्षे । ६ । २ । ६७ । गवाध्यक्षः ।

३८०२ । पापं च शिल्पिनि । ६ । २ । ६८ । पापनापितः । 'पापाणके–' (सू ७३३) इति प्रतिपदोक्तस्यैव ग्रहणात्षष्ठीसमासे न ।

३८०३ । गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे । ६ । २ । ६९ । भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्राण्यधीयते त एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । 'गोत्रादिषु' किम् । दासीश्रोत्रियः । 'क्षेपे' किम् । परमब्राह्मणः ।

३८०४ । अङ्गानि मैरेये । ६ । २ । ७० । मद्यविशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । 'अङ्गानि' किम् । परममैरेयः । 'मैरेये' किम् । पुष्पासवः ।

३८०५ । भक्ताख्यास्तदर्थेषु । ६ । २ । ७१ । भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । 'भक्ताख्याः' किम् । समाशशालयः । समशनं समाश इति क्रियामात्रमुच्यते । 'तदर्थेषु' किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ।

३८०६ । गोबिडालसिंहसैन्धवेषूपमाने । ६ । २ । ७२ । धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या संनिवेशितं धान्यं धान्यगवशब्देनोच्यते । 'उपमाने' किम् । परमसिंहः ।

३८०७ । अके जीविकार्थे । ६ । २ । ७३ । अकप्रत्ययान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तम् । दन्तलेखकः । यस्य दन्तलेखनेन जीविका । 'नित्यं क्रीड–' (सू ७११) इति समासः । 'अके' किम् । रमणीयकर्ता । 'जीविकार्थे' किम् । इक्षुभक्षिकां मे धारयसि ।

३८०८ । प्राचां क्रीडायाम् । ६ । २ । ७४ । प्राग्देशवाचिनां या क्रीडा तद्वाचिनि समास अकप्रत्ययान्तेपरे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । 'संज्ञायाम्' (सू ३२८६) इति ण्वुल् । 'प्राचाम्' किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । 'क्रीडायाम्' किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ।

३८०९ । अणि नियुक्ते । ६ । २ । ७५ । अणन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्रधारः । 'नियुक्ते' किम् । काण्डलावः ।

३८१० । शिल्पिनि चाकृञः । ६ । २ । ७६ । शिल्पिवाचिनि समासेऽण्णन्ते परे पूर्वमाद्युदात्तं स चेदण्कृञः परो न भवति । तन्तुवायः । 'शिल्पिनि' किम् । काण्डलावः । 'अकृञः' किम् । कुम्भकारः ।

३८११ । संज्ञायां च । ६ । २ । ७७ । अण्णन्ते परे । तन्तुवायो नाम कृमिः । 'अकृञः' इत्येव । रथकारो नाम ब्राह्मणः ।

३८१२। गोतन्तियवं पाले। ६। २। ७८। गोपालः। तन्तिपालः। यवपालः। अनियुक्तार्थो योगः। 'गो' इति किम्। वत्सपालः। 'पाले' इति किम्। गोरक्षः।

३८१३। णिनि। ६। २। ७९। पुष्पहारी।

३८१४। उपमानं शब्दार्थप्रकृतावेव। ६। २। ८०। उपमानवाचि पूर्वपदं णिन्यन्ते पर आद्युदात्तम्। उष्ट्रक्रोशी। ध्वाङ्क्षरावी। उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम्। 'शब्दार्थप्रकृतौ' किम्। वृकवञ्ची। 'प्रकृतिग्रहणम्' किम्। प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात्। इह मा भूत्। गर्दभोच्चारी।

३८१५। युक्तारोह्यादयश्च। ६। २। ८१। आद्युदात्ताः। युक्तारोही। आगतयोधी। क्षीरहोता।

३८१६। दीर्घकाशतुषभ्राष्ट्रवटं जे। ६। २। ८२। कुटीजः। काशजः। तुषजः। भ्राष्ट्रजः। वटजः।

३८१७ अन्त्यात्पूर्वं बह्वचः। ६। २। ८३। बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं ज उत्तरपदे। उपसरजः। आमलकीजः। 'बह्वचः' किम्। दग्धजानि तृणानि।

३८१८। ग्रामेऽनिवसन्तः। ६। २। ८४। ग्रामे परे पूर्वपदमुदात्तम्। तच्चेन्निवसद्वाचि न। मल्लग्रामः। ग्रामशब्दोऽत्र समूहवाची। देवग्रामः। देवस्वामिकः। 'अनिवसन्तः' किम्। दाक्षिग्रामः। दाक्षिनिवासः।

३८१९। घोषादिषु च। ६। २। ८५। दाक्षिघोषः। दाक्षिकटः। दाक्षिह्रदः।

३८२०। छात्र्यादयः शालायाम्। ६। २। ८६। छात्रिशाला। व्याडिशाला। यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि 'तत्पुरुषे शालायां नपुंसके' (सू ३८५७) इत्येतस्मात्पूर्वविप्रतिषेधेनायमेव स्वरः। छात्रिशालम्।

३८२१। प्रस्थेऽवृद्धमकर्क्यादीनाम्। ६। २। ८७। प्रस्थशब्द उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात्। इन्द्रप्रस्थः। 'अवृद्धम्' किम्। दाक्षिप्रस्थः। 'अकर्क्यादीनाम्' इति किम्। कर्कीप्रस्थः। मकरीप्रस्थः।

३८२२। मालादीनां च। ६। २। ८८। वृद्धार्थमिदम्। मालाप्रस्थः। शालाप्रस्थः।

३८२३। अमहन्नवन्नगरेऽनुदीचाम्। ६। २। ८९। नगरे परे महन्नवन्वर्जितं पूर्वमाद्युदात्तं स्यात् तच्चेदुदीचां न। ब्रह्मनगरम्। 'अम-' इति किम्। महानगरम्। नवनगरम्। 'अनुदीचाम्' किम्। कार्तिनगरम्।

३८२४। अर्मे चावर्णं द्व्यच्त्र्यच्। ६। २। ९०। अर्मे परे द्व्यच्त्र्यच्पूर्वमवर्णान्तमाद्युदात्तम्। गुप्तार्मम्। कुक्कुटार्मम्। 'अवर्णम्' किम्। बृहदर्मम्। 'द्व्यच्त्र्यच्' किम्। कपिञ्जलार्मम्। अमहन्नवन्नित्येव। महार्मम्। नवार्मम्।

३८२५। न भूताधिकसंजीवमद्राश्मकज्जलम्। ६। २। ९१। अर्मे परे नैतान्याद्युदात्तानि। भूतार्मम्। अधिकार्मम्। संजीवार्मम्। मद्राश्मग्रहणं संघातविगृहीतार्थम्। मद्रार्मम्। अश्मार्मम्। मद्राश्मार्मम्। कज्जलार्मम्। 'आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम्' (वा ३८४०)। 'दिवोदासाय दाशुषे'।

३८२६। अन्तः। ६। २। ९२। अधिकारोऽयम्। प्रागुत्तरपदादिग्रहणात्।

३८२७। सर्वं गुणकार्त्स्न्ये। ६। २। ९३। सर्वशब्दः पूर्वपदमन्तोदात्तम्। सर्वश्वेतः। सर्वमहान्। 'सर्वम्' किम्। परमश्वेतः। आश्रयव्याप्त्या परमत्वं श्वेतस्येति। गुणकार्त्स्न्ये वर्तते। 'गुण-' इति किम्। सर्वसौवर्णः। 'कार्त्स्न्ये' किम्। सर्वेषां श्वेततरः सर्वश्वेतः।

३८२८। संज्ञायां गिरिनिकाययोः। ६। २। ९४। एतयोः परतः पूर्वमन्तोदात्तम्। अञ्जनागिरिः मौण्डनिकायः। 'संज्ञायाम्' किम्। परमगिरिः। ब्राह्मणनिकायः।

३८२९। कुमार्यां वयसि। ६। २। ९५। पूर्वपदमन्तोदात्तम्। वृद्धकुमारी। कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः। तच्च वय इह गृह्यते न कुमारत्वमेव। 'वयसि' किम्। परमकुमारी।

३८३०। उदकेऽकेवले। ६। २। ९६। अकेवलं मिश्रं तद्वाचिनि समास उदके परे पूर्वमन्तोदात्तम्। गुडोदकम्। स्वरे कृतेऽत्र एकादेशः। 'स्वरितो वानुदात्ते पदादौ' (सू ३६५९) इति पक्षे स्वरितः। 'अकेवले' किम्। शीतोदकम्।

३८३१। द्विगौ क्रतौ। ६। २। ९७। द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वमन्तोदात्तम्। गर्गत्रिरात्रः। 'द्विगौ' किम्। अतिरात्रः। 'क्रतौ' किम्। बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः।

३८३२। सभायां नपुंसके। ६। २। ९८। सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम्। गोपालसभम्। स्त्रीसभम्। 'सभायाम्' किम्। ब्राह्मणसेनम्। 'नपुंसके' किम्। राजसभा। प्रतिपदोक्तनपुंसकग्रहणान्नेह। रमणीयसभम्। ब्राह्मणकुलम्।

३८३३। पुरे प्राचाम्। ६। २।। ९९। देवदत्तपुरम्। नान्दीपुरम्। 'प्राचाम्' किम्। शिवपुरम्।

३८३४। अरिष्टगौडपूर्वे च। ६। २। १००। पुरे परेऽरिष्टगौडपूर्वे समासे पूर्वमन्तोदात्तम्। अरिष्टपुरम्। गौडपुरम्। 'पूर्व' ग्रहणं किम्। इहापि यथा स्यात्। अरिष्टाश्रितपुरम्। गौडभृत्यपुरम्।

३८३५। न हास्तिनफलकमार्देयाः। ६। २। १०१। पुरे परे नैतान्यन्तोदात्तानि। हास्तिनपुरम्। फलकपुरम्। मार्देयपुरम्। मृदेरपत्यमिति शुभ्रादित्वात् ढक्।

३८३६। कुसूलकूपकुम्भशालं बिले। ६। २। १०२। एतान्यन्तोदात्तानि बिले परे। कुसूलबिलम्। कूपबिलम्। कुम्भबिलम्। शालबिलम्। 'कुसूलादि' किम्। सर्पबिलम्। 'बिल' इति किम्। कुसूलस्वामी।

३८३७। दिक्छब्दा ग्रामजनपदाख्यानचानराटेषु। ६। २। १०३। दिक्छब्दा अन्तोदात्ता भवन्त्येषु। पूर्वेषुकामशमी। अपरकृष्णमृत्तिका। जनपदे। पूर्वपञ्चालाः। आख्याने। पूर्वयायातम्। पूर्वचानराटम्। शब्दग्रहणं कालवाचिदिक्छब्दस्य परिग्रहार्थम्।

३८३८। आचार्योपसर्जनश्चान्तेवासिनि। ६। २। १०४। आचार्योपसर्जनान्तेवासिनि परे दिक्छब्दा अन्तोदात्ता भवन्ति। पूर्वपाणिनीयाः। 'आचार्य-' इति किम्। पूर्वान्तेवासी। 'अन्तेवासिनि' किम्। पूर्वपाणिनीयं शास्त्रम्।

३८३९। उत्तरपदवृद्धौ सर्वं च। ६। २। १०५। उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता

तद्युत्तरपदे परे सर्वशब्दो दिक्छब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । 'अधिकार' ग्रहणं किम् । सर्वभासः । सर्वकारकः ।

३८४० । बहुव्रीहौ विश्वं संज्ञायाम् । ६ । २ । १०६ । बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । 'विश्वकर्मा विश्वदेवः' । 'आविश्वदेवं सत्पतिम्' । 'बहुव्रीहौ' किम् । विश्वे च ते देवाश्च विश्वेदेवाः । 'संज्ञायाम्' किम् । विश्वदेवः । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ।

३८४१ । उदराश्वेषुषु । ६ । २ । १०७ । संज्ञायामिति वर्तते । वृकोदरः । हर्यश्वः । महेषुः ।

३८४२ । क्षेपे । ६ । २ । १०८ । उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कन्दुकाश्वः । चलाचलेषुः । अनुदर इत्यत्र 'नञ्सुभ्याम्–' (सू ३९०६) इति भवति विप्रतिषेधेन ।

३८४३ । नदी बन्धुनि । ६ । २ । १०९ । बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ गार्गीबन्धुः । 'नदी' किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । 'बन्धुनि' किम् । गार्गीप्रियः ।

३८४४ । निष्ठोपसर्गपूर्वमन्यतरस्याम् । ६ । २ । ११० । निष्ठान्तं पूर्वपदमन्तोदात्तं वा । प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । 'उपसर्गपूर्वम्' किम् । शुष्कमुखः ।

३८४५ । उत्तरपदादिः । ६ । २ । १११ । उत्तरपदाधिकार आपादान्तम् । आद्यधिकारस्तु 'प्रकृत्या भगालम्' (सू ३८७१) इत्यवधिकः ।

३८४६ । कर्णो वर्णलक्षणात् । ६ । २ । ११२ । कर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । 'कर्णः' किम् । श्वेतपादः । 'वर्णलक्षणात्' किम् । शोभनकर्णः ।

३८४७ । संज्ञौपम्ययोश्च । ६ । २ । ११३ । कर्ण आद्युदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ।

३८४८ । कण्ठपृष्ठग्रीवाजङ्घं च । ६ । २ । ११४ । संज्ञौपम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ।

३८४९ । शृङ्गमवस्थायां च । ६ । २ । ११५ । शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । 'अवस्था–' इति किम् । स्थूलशृङ्गः ।

३८५० । नञो जरमरमित्रमृताः । ६ । २ । ११६ । नञः पर एते आद्युदात्ता बहुव्रीहौ । 'ता मे जराय्वजरम्' । अमरम् । 'आमित्रमर्दय' । 'श्रवो देवेष्वमृतम्' । 'नञः' किम् । ब्राह्मणमित्रः । 'ज–' इति किम् । अशत्रुः ।

३८५१ । सोर्मनसी अलोमोषसी । ६ । २ । ११७ । सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । 'नञ्सुभ्याम्' (सू ३९०६) इत्यस्यापवादः । 'सुकर्माणः सुयुजः' । 'स नो वक्षदनिमानः सुवत्मा' । 'शिवा पशुभ्यः सुमनाः सुवर्चाः' । 'सुपेशसस्करति' ।

'सोः' किम् । कृतकर्मा । 'मनसी' किम् । सुराजा । 'अलोमोषसी' किम् । सुलोमा । सूषाः कपि तु परत्वात् । 'कपि पूर्वम्' (सू ३९०७)इति भवति । सुकर्मकः । 'सुस्रोतस्कः' ।

३८५२ । क्त्वादयश्च । ६ । २ । ११८ । सोः पर आद्युदात्ताः स्युः । 'साधोज्याय सुक्रतुः' । 'सुप्रतीकः' । 'सुहव्यः' । 'सुप्रतूर्तिमनेहसम्' ।

३८५३ । आद्युदात्तं द्व्यच्छन्दसि । ६ । २ । ११९ । यदाद्युदात्तं द्व्यच्तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् । 'अधा स्वश्वाः' । सुरथाँ आतिथिग्वे' । नित्स्वरेणाश्वरथावाद्युदात्तौ । 'आद्युदात्तम्' किम् । 'यासुंबाहुः' । 'द्व्यच्' किम् । सुगुरसत्सुहिरण्यः । हिरण्यशब्दस्त्र्यच् ।

३८५४ । वीरवीर्यौ च । ६ । २ । १२० । सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । 'सुवीरेण रयिणा' । 'सुवीर्यस्य गोमतः' । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र 'यतोऽनावः' (सू ३७०१) इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ।

३८५५ । कूलतीरतूलमूलशालाक्षसममव्ययीभावे । ६ । २ । १२१ । उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । 'कूलादि' ग्रहणं किम् । उपकुम्भम् । 'अव्ययीभावे' किम् । परमकूलम् ।

३८५६ । कंसमन्थशूर्पपाय्यकाण्डं द्विगौ । ६ । २ । १२२ । द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । 'द्विगौ' किम् । परमकंसः

३८५७ । तत्पुरुषे शालायां नपुंसके । ६ । २ । १२३ । शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गे उत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । 'तत्पुरुषे' किम् । दृढशालं ब्राह्मणकुलम् । 'शालायाम्' किम् । ब्राह्मणसेनम् । 'नपुंसके' किम् । ब्राह्मणशाला ।

३८५८ । कन्था च । ६ । २ । १२४ । तत्पुरुषे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् । आह्वरकन्थम् । 'नपुंसके' किम् । दाक्षिकन्था ।

३८५९ । आदिश्चिहणादीनाम् । ६ । २ । १२५ । कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहणकन्थम् । मन्दकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ।

३८६० । चेलखेटकटुककाण्डं गर्हायाम् । ६ । २ । १२६ । चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नगरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा । व्याघ्रादित्वात्समासः । 'गर्हायाम्' किम् । परमचेलम् ।

३८६१ । चीरमुपमानम् । ६ । २ । १२७ । वस्त्रं चीरमिव वस्त्रचीरं । कम्बलचीरम् । 'उपमानं' किम् । परमचीरम् ।

३८६२ । पललसूपशाकं मिश्रे । ६ । २ । १२८ । घृतपललम् । घृतसूपः । घृतशाकम् । 'भक्ष्येण मिश्रीकरणम्' (सू ६९७)इति समासः । 'मिश्रे' किम् । परमपललम् ।

३८६३ कूलसूदस्थलकर्षाः संज्ञायाम् । ६ । २ । १२९ । आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । 'संज्ञायाम्' किम् । परमकूलम् ।

३८६४ । अकर्मधारये राज्यम् । ६ । २ । १३० । कर्मधारयवर्जिते तत्पुरुषे राज्य-

मुत्तरपदमाद्युदात्तम्। ब्राह्मणराज्यम्। 'अक-' इति किम्। परमराज्यम्। 'चेलराज्या-दिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन' (वा ३८४७) कुचेलम्। कुराज्यम्।

३८६५। वर्ग्यादयश्च। ६। २। १३१। अर्जुनवर्ग्यः। वासुदेवपक्ष्यः। अकर्मधारय इत्येव। परमवर्ग्यः। वर्ग्यादिर्दिगाद्यन्तर्गणः।

३८६६। पुत्रः पुम्भ्यः। ६। २। १३२। पुम्शब्देभ्यः परः पुत्रशब्द आद्युदात्तः स्तत्पुरुषे। दाशकिपुत्रः। माहिषपुत्रः। 'पुत्रः' किम्। कौनटिमातुलः। 'पुम्भ्यः' किम्। दाक्षीपुत्रः।

३८६७। नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः। ६। २। १३३। एभ्यः पुत्रो नाद्युदात्तः। आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम्। आचार्यपुत्रः। उपाध्यायपुत्रः। शाकटायनपुत्रः। राजपुत्रः। ईश्वरपुत्रः। नन्दपुत्रः। ऋत्विक्पुत्रः। याजकपुत्रः। होतुःपुत्रः। संयुक्ताः। संबन्धिनः। श्यालपुत्रः। ज्ञातयो मातापितृसंबन्धेन बान्धवाः। ज्ञातिपुत्रः। भ्रातुःपुत्रः।

३८६८। चूर्णादीन्यप्राणिषष्ठ्याः। ६। २। १३४। एतानि प्राणिभिन्नषष्ठ्यन्तात्परा-ण्याद्युदात्तानि तत्पुरुषे। मुद्गचूर्णम् 'अप्रा-' इति किम्। मत्स्यचूर्णम्।

३८६९। षट् च काण्डादीनि। ६। २। १३५। अप्राणिषष्ठ्या आद्युदात्तानि। दर्भ-काण्डम्। दर्भचीरम्। तिलपललम्। मुद्गसूपः। मूलकशाकम्। नदीकूलम्। 'षट्' किम्। राजसूदः। 'अप्रा-' इति किम्। दत्तकाण्डम्।

३८७०। कुण्डं वनम्। ६। २। १३६। कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे। दर्भकुण्डम्। कुण्डशब्दोऽत्र सादृश्ये। 'वनम्' किम्। मृत्कुण्डम्।

३८७१। प्रकृत्या भगालम्। ६। २। १३७। भगालवाच्युत्तरपदम्। तत्पुरुषे प्र-कृत्या। कुम्भीभगालम्। कुम्भीनदालम्। कुम्भीकपालम्। मध्योदात्ता एते 'प्रकृत्या' इत्यधि-कृतम् 'अन्तः' (सू ३८७७) इति यावत्।

३८७२। शितेर्नित्याबह्वज्बहुव्रीहावभसत्। ६। २। १३८। शितेः परं नित्याबह्वच्कं प्रकृत्या। शितिपादः। शित्यंसः। पादशब्दो वृषादित्वादाद्युदात्तः। अंसशब्दः प्रत्ययस्य नित्त्वात्। 'शितेः' किम्। दर्शनीयपादः। 'अभसत्' किम्। शितिभसत्। शितिराद्युदात्तः। पूर्वपदप्रकृतिस्वरापवादोऽयं योगः।

३८७३। गतिकारकोपपदात्कृत्। ६। २। १३९। एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्त-त्पुरुषे। प्रकारकः। प्रहरणम्। 'शोणा धृष्णू नृवाहसा'। इध्मप्रव्रश्चनः। उपपदात् उच्चैःकारम्। ईषत्करः। 'गति' इति किम्। देवस्य कारकः। शेषे षष्ठी। कृद्ग्रहणं स्पष्टार्थम्। प्रपचतितरामित्यत्र तारबाद्यन्तेन समासे कृत आम्। तत्र सतिशिष्टत्वादाम्स्वरो भवती-त्येके। प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये।

३८७४ उभे वनस्पत्यादिषु युगपत्। ६। २। १४०। एषु पूर्वोत्तरपदे युगपत्प्रकृत्या। 'वनस्पतिं वन आ'। 'बृहस्पतिं यः' बृहच्छब्दोऽत्राद्युदात्तो निपात्यते। 'हर्षया शचीप-तिम्'। शार्ङ्गरवादित्वादाद्युदात्तः शचीशब्दः। 'शचीभिर्नः' इति दर्शनात्। 'तनूनपादुच्यते'। 'नराशंसं वाजिनम्'। निपातनाद्दीर्घः। 'शुनःशेपम्'।

३८७५ । देवताद्वन्द्वे च । ६ । २ । १४१ । उभे युगपत्प्रकृत्या स्तः । 'आप इन्द्रावरुणौ' । 'इन्द्राबृहस्पती वयम्' । 'देवता' किम् । प्लक्षन्यग्रोधौ । 'द्वन्द्वे' किम् । अग्निष्टोमः ।

३८७६ । नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु । ६ । २ । १४२ । पृथिव्यादिवर्जिते ऽनुदात्तादावुत्तरपदे प्रागुक्तं न । 'इन्द्राग्निभ्यां कं वृषणः' । 'अपृथिव्यादौ' किम् । 'द्यावापृथिवी जनयन्' । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । रुद्रसोमौ । 'रोदेर्णिलुक्च' (उणा०) इति रगन्तो रुद्रशब्दः । 'इन्द्रापूषणौ' । 'श्वन्नुक्षन्पूषन्-' (उणा०) इति पूषाऽन्तोदात्तो निपात्यते । शुक्रामन्थिनौ । मन्थिन्निनन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्याद्द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ।

३८७७ । अन्तः । ६ । २ । १४३ । अधिकारोऽयम् ।

३८७८ । थाथघञ्क्ताजबित्रकाणाम् । ६ । २ । १४४ । 'थ' 'अथ' 'घञ्' 'क्त' 'अच्' 'अप्' 'इत्र' 'क' एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । 'प्रभृथस्यायोः' । आवसथः । घञ् । प्रभेदः । क्त । 'भर्ता वज्री पुरुष्टुतः' । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ।

३८७९ । सूपमानात्क्तः । ६ । २ । १४५ । सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । 'कृतस्य योनौ सुकृतस्य' । शशप्लुतः ।

३८८० । संज्ञायामनाचितादीनाम् । ६ । २ । १४६ । गतिकारकोपपदात्क्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा । उपहूतः शाकल्यः । परिजग्धः । कौण्डिन्यः । 'अन-' इति किम् । आचितम् । आस्थापितम् ।

३८८१ । प्रवृद्धादीनां च । ६ । २ । १४७ । एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रवृद्धः । प्रयुक्तः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ।

३८८२ । कारकाद्दत्तश्रुतयोरेवाशिषि । ६ । २ । १४८ । संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । 'कारकात्' किम् । संभूतो रामायणः । 'दत्तश्रुतयोः' किम् । देवपालितः अस्मान्नियमादत्र 'संज्ञायामन-' (सू ३८८०) इति न । 'तृतीयाकर्मणि' (सू ३७८२) इति तु भवति । 'एव' किम् । 'कारकावधारणं' यथा स्याद्दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति । संश्रुतः । 'आशिषि' किम् । देवैः खाता देवखाता । आशिष्येवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न । शङ्खविशेषस्य संज्ञेयम् । 'तृतीया कर्मणि' (सू ३७८२) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ।

३८८३ । इत्थंभूतेन कृतमिति च । ६ । २ । १४९ । इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । 'तृतीया कर्मणि' (सू ३७८२) इत्यस्यापवादः ।

३८८४ । अनो भावकर्मवचनः । ६ । २ । १५० । कारकात्परमनप्रत्ययान्तं भाववचनं

कर्मवचनं चान्तोदात्तम्। पयःपानं सुखम्। राजभोजनाः शालयः। 'अनः' किम्। हस्तादायः। 'भा–' इति किम्। दन्तधावनम्। करणे ल्युट्। 'कारकात्' किम्। निदर्शनम्।

३८८५। मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः। ६।२।१५१। कारकात्पराण्येतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे। कृत्स्वरापवादः। रथवर्त्म। पाणिनिकृतिः। छन्दोव्याख्यानम्। राजशयनम्। राजासनम्। अश्वस्थानम्। ब्राह्मणयाजकः। गोक्रीतः। 'कारकात्' किम्। 'प्रभूतौ संगतिम्'। अत्र 'तादौ च निति–' (सू ३७८४) इति स्वरः।

३८८६। सप्तम्याः पुण्यम्। ६।२।१५२। अन्तोदात्तम्। अध्ययनपुण्यम्। 'तत्पुरुषे तुल्यार्थ–' (सू ३७३६) इति प्राप्तम्। 'सप्तम्याः' किम्। वेदेन पुण्यं वेदपुण्यम्।

३८८७। ऊनार्थकलहं तृतीयायाः। ६।२।१५३। माषोनम्। माषविकलम्। वाक्कलहः। तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम्। अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति। धान्यार्थः। ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम्।

३८८८। मिश्रं चानुपसर्गमसंधौ। ६।२।१५४। पणबन्धेनैकार्थ्यं संधिः। तिलमिश्राः। सर्पिर्मिश्राः। 'मिश्रम्' किम्। गुडधानाः। 'अनुपसर्गम्' किम्। तिलसंमिश्राः। 'मिश्रग्रहणे सोपसर्गग्रहणस्य' इदमेव ज्ञापकम्। 'असंधौ' किम्। ब्राह्मणमिश्रो राजा। ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः।

३८८९। नञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्तद्धिताः। ६।२।१५५। संपाद्याद्यर्थतद्धितान्तान्नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः। कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम्। न कार्णवेष्टकिकमकार्णवेष्टकिकम्। छेदमर्हति छैदिकः। न छैदिकोऽच्छैदिकः। न वत्सेभ्यो हितोऽवात्सीयः। न संतापाय प्रभवति असंतापिकः। 'नञः' किम्। गर्दभरथमर्हति गार्दभरथिकः। विगार्दभरथिकः 'गुणप्रतिषेधे' किम्। गार्दभरथिकादन्योऽगार्दभरथिकः। गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते। तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः। कर्णवेष्टकाभ्यां न संपादि मुखमिति। 'संपादि–' इति किम्। पाणिनीयमधीते पाणिनीयः। न पाणिनीयः अपाणिनीयः। 'तद्धिताः' किम्। वोढुमर्हति वोढा। न वोढा अवोढा।

३८९०। ययतोश्चातदर्थे। ६।२।१५६। ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात्। पाशानां समूहः पाश्या। न पाश्या अपाश्या। अदन्त्यम्। 'अतदर्थे' किम्। अपाद्यम्। 'तद्धितः' किम्। अदेयम्। 'गुणप्रतिषेधे' किम्। दन्त्यादन्यददन्त्यम्। 'तदनुबन्धग्रहणे नातदनुबन्धकस्य' इति। नेह। अवामदेव्यम्।

३८९१। अच्कावशक्तौ। ६।२।१५७। अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम्। अपचः पक्तुमशक्तः। अविलिखः। 'अशक्तौ' किम्। अपचो दीक्षितः। गुणप्रतिषेध इत्येव। अन्योऽयं पचादपचः।

३८९२। आक्रोशे च। ६।२।१५८। नञः परावच्कावन्तोदात्तावाक्रोशे। अपचो जाल्मः। पक्तुं न शक्नोतीत्येवमाक्रोश्यते। अविक्षिपः।

३८९३। संज्ञायाम्। ६।२।१५९। नञः परमन्तोदात्तं संज्ञायामाक्रोशे। अदेवदत्तः।

26*

३८९४ । कृत्योकेष्णुच्चार्वादयश्च । ६ । २ । १६० । नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलंकरिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः असाधुः । 'राजाह्नोश्छन्दसि' (गण १६१) । अराजा । अनहः । 'भाषायाम्' नञः स्वर एव ।

३८९५ । विभाषा तृन्नन्नतीक्ष्णशुचिषु । ६ । २ । १६१ । तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि । पक्षेऽव्ययस्वरः ।

३८९६ । बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने । ६ । २ । १६२ । एभ्योऽनयोरन्त उदात्तः । इदं प्रथममस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । 'बहुव्रीहौ' किम् । अनेन प्रथम इदंप्रथमः । 'तृतीया-' (सू ६९२) इति योगविभागात्समासः । 'इदमेतत्तद्भ्यः' किम् । यत्प्रथमः । 'प्रथमपूरणयोः' किम् । तानि बहून्यस्य तद्बहुः । 'क्रियागणने' किम् । अयं प्रथमः प्रधानं येषां त इदंप्रथमाः । द्रव्यगणनमिदम् । 'गणने' किम् । अयं प्रथम एषां त इदंप्रथमाः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकाः । बहुव्रीहावित्यधिकारो 'वनं समासे' (सू ३९१२) इत्यतः प्राग्बोध्यः ।

३८९७ । संख्यायाः स्तनः । ६ । २ । १६३ । बहुव्रीहावन्तोदात्तः । द्विस्तना । चतुस्तना । 'संख्यायाः' किम् । दर्शनीयस्तना । 'स्तनः' किम् । द्विशिराः ।

३८९८ । विभाषा छन्दसि । ६ । २ । १६४ । 'द्विस्तनां करोति' ।

३८९९ । संज्ञायां मित्राजिनयोः । ६ । २ । १६५ । देवमित्रः । कृष्णाजिनम् । 'संज्ञायाम्' किम् । प्रियमित्रः । 'ऋषिप्रतिषेधोऽत्र मित्रे' (वा ३८९७)' । विश्वामित्रर्षिः ।

३९०० । व्यवायिनोऽन्तरम् । ६ । २ । १६६ । व्यवधानवाचकात्परमन्तरमन्तोदात्तम् । वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः । 'व्यवधायिनः' किम् । आत्मान्तरः । अन्यस्वभाव इत्यर्थः ।

३९०१ । मुखं स्वाङ्गम् । ६ । २ । १६७ । गौरमुखः । 'स्वाङ्गम्' किम् । दीर्घमुखा शाला ।

३९०२ । नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः । ६ । २ । १६८ । उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः । मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ।

३९०३ । निष्ठोपमानादन्यतरस्याम् । ६ । २ । १६९ । निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे 'निष्ठोपसर्ग-' (सू ३८४४) इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति । उपमानम् । सिंहमुखः ।

३९०४ । जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमितप्रतिपन्नाः । ६ । २ । १७० । सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । 'जातिकाल-' इति किम् । पुत्रजातः । 'अनाच्छादनात्' किम् । वस्त्रच्छन्नः । 'अकृत-' इति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ।

३९०५ । वा जाते । ६ । २ । १७१ । जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ।

३९०६ । नञ्सुभ्याम् । ६ । २ । १७२ । बहुव्रीहावुत्तरपदमन्तोदात्तम् । अव्रीहिः । सुमाषः ।

३९०७ । कपि पूर्वम् । ६ । २ । १७३ । नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ।

३९०८ । ह्रस्वान्तेऽन्त्यात्पूर्वम् । ६ । २ । १७४ । ह्रस्वान्त उत्तरपदे समासे चान्त्यात्पूर्वमुदात्तं कपि नञ्सुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । ह्रस्वान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति । अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ।

३९०९ । बहोर्नञ्वदुत्तरपदभूम्नि । ६ । २ । १७५ । उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । 'उत्तरपद–' इति किम् । बहुषु मानोऽस्य स बहुमानः ।

३९१० । न गुणादयोऽवयवाः । ६ । २ । १७६ । अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुणा रज्जुः । बह्वक्षरं पदम् । बह्वध्यायः । गुणादिराकृतिगणः । 'अवयवाः' किम् । बहुगुणो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ।

३९११ । उपसर्गात्स्वाङ्गं ध्रुवमपर्शु । ६ । २ । १७७ । प्रपृष्ठः । प्रललाटः । ध्रुवमेकरूपम् । 'उपसर्गात्' किम् । दर्शनीयपृष्ठः । 'स्वाङ्गम्' किम् । प्रशाखो वृक्षः । 'ध्रुवम्' किम् । उद्बाहुः । 'अपर्शु' किम् । विपर्शुः ।

३९१२ । वनं समासे । ६ । २ । १७८ । समासमात्र उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे ।

३९१३ । अन्तः । ६ । २ । १७९ । अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ।

३९१४ । अन्तश्च । ६ । २ । १८० । उपसर्गादन्तःशब्दोऽन्तोदात्तः । पर्यन्तः । समन्तः ।

३९१५ । न निविभ्याम् । ६ । २ । १८१ । न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरे यणि च कृते 'उदात्तस्वरितयोर्यणः–' (सू ३६५७) इति स्वरितः ।

३९१६ । परेरभितोभावि मण्डलम् । ६ । २ । १८२ । परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ।

३९१७ । प्रादस्वाङ्गं संज्ञायाम् । ६ । २ । १८३ । प्रगृहम् । 'अस्वाङ्गम्' किम् । प्रपदम् ।

३९१८ । निरुदकादीनि च । ६ । २ । १८४ । अन्तोदात्तानि । निरुदकम् । निरुपलम् ।

३९१९ । अभेर्मुखम् । ६ । २ । १८५ । अभिमुखम् । 'उपसर्गात्स्वाङ्गम्–' (सू ३९११) इति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च । अभिमुखा शाला ।

३९२० अपाच्च । ६ । २ । १८६ । अपमुखम् । योगविभाग उत्तरार्थः ।

३९२१ । स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम च । ६ । २ । १८७ । अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । 'उपसर्गादध्वनः' (सू ९५३) इत्यस्याभाव इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे । अपकुक्षि । सीरनाम । अपसीरम् । अपहलम् । नाम । अपनाम । स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ।

३९२२ । अधेरुपरिस्थम् । ६ । २ । १८८ । अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरिजातो दन्तः । 'उपरिस्थम्' किम् । अधिकरणम् ।

३९२३ । अनोरप्रधानकनीयसी । ६ । २ । १८९ । अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । 'अप्र–' इति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ।

३९२४ । पुरुषश्चान्वादिष्टः । ६ । २ । १९० । अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्टः पुरुषोऽनुपुरुषः । 'अन्वादिष्टः' किम् । अनुगतः पुरुषोऽनुपुरुषः ।

३९२५ । अतेरकृत्पदे । ६ । २ । १९१ । अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदा गायत्री । 'अकृत्पदे' किम् । अतिकारकः । 'अतेर्धातुलोप इति वाच्यम्' (वा ३८६३) । इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ।

३९२६ । नेरनिधाने । ६ । २ । १९२ । निधानमप्रकाशता । ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । 'अनिधाने' किम् । निहितो दण्डो निदण्डः ।

३९२७ । प्रतेरंश्वादयस्तत्पुरुषे । ६ । २ । १९३ । प्रतेः परेऽश्वादयोऽन्तोदात्ताः । प्रतिगतोंऽशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ।

३९२८ । उपाद्द्व्यजजिनमगौरादयः । ६ । २ । १९४ । उपात्परं यद्द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । 'अगौरादयः' किम् । उपगौरः । उपतैषः । 'तत्पुरुषे' किम् । उपगतः सोमोऽस्य स उपसोमः ।

३९२९ । सोरवक्षेपणे । ६ । २ । १९५ । सुप्रत्यवसितः । सुरत्र पूजायामेव वाक्यार्थस्त्वत्र निन्दा असूयया तथाभिधानात् । 'सोः' किम् । कुब्राह्मणः । 'अवक्षेपणे' किम् । सुवृषणम् ।

३९३० । विभाषोत्पुच्छे । ६ । २ । १९६ । तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः 'एरच्' (सू ३२३१) उत्पुच्छः, तदा थाथादिस्वरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । 'तत्पुरुषे' किम् । उदस्तं पुच्छं येन स उत्पुच्छः ।

३९३१ । द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ । ६ । २ । १९७ । आभ्यां परेष्वेष्वन्तोदात्तो वा । 'द्विपाच्चतुष्पाच्च रथाय' । 'त्रिपादूर्ध्वः' । द्विदन् । 'त्रिमूर्धानं सप्तरश्मिम्' । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकम् 'अनित्यः समासान्तो भवति' इति । यद्यपि च समासान्तः

क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव । द्विमूर्धः त्रिमूर्धः । 'द्वित्रिभ्याम्' किम् । कल्याणमूर्धा । 'बहुव्रीहौ' किम् । द्वयोर्मूर्धा द्विमूर्धा ।

३९३२ । सक्थं चाक्रान्तात् । ६ । २ । १९८ । गौरसक्थः । श्लक्ष्णसक्थः । 'आक्रान्तात्' किम् । चक्रसक्थः । समासान्तस्य षचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ।

३९३३ । परादिश्छन्दसि बहुलम् । ६ । २ । १९९ । छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । 'अजिसक्थमालभेत' । अत्र वार्तिकम्—

'परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते ।
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः' ॥ (वा ३८६८–६९)

इति । परादिः । 'तुविजाता उरुक्षया' । परान्तः । 'नियेन मुष्टिहत्यया' । 'याश्चिचक्रः' पूर्वान्तः । 'विश्वायुर्धेहि' ।

इति समासस्वराः

३९३४ । तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः । ८ । १ । २७ । तिङन्तात्पदाद्गोत्रादीन्यनुदात्तान्येतयोः । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । 'गोत्रादि–' इति किम् । पचति पापम् । 'कुत्स–' इति किम् । खनति गोत्रं समेत्य कूपम् ।

३९३५ । तिङ्ङतिङः । ८ । १ । २८ । अतिङन्तात्पदात्परं तिङन्तं निहन्यते । 'अग्निमीळे' ।

३९३६ । न लुट् । ८ । १ । २९ । लुडन्तं न निहन्यते । श्वः कर्ता ।

३९३७ । निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् । ८ । १ । ३० । एतैर्निपातैर्युक्तं न निहन्यते । 'यदग्ने स्यामहत्वम्' । 'युवा यदी कृथः' । 'कुविदङ्ग आसन्' । 'आचित्तिभिश्चकृमा कच्चित्' । 'पुत्रासो यत्र पितरो भवन्ति' ।

३९३८ । नह प्रत्यारम्भे । ८ । १ । ३१ । नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । 'नह भोक्ष्यसे' । 'प्रत्यारम्भे' किम् । 'नह वैतस्मिँल्लोके दक्षिणमिच्छन्ति' ।

३९३९ । सत्यं प्रश्ने । ८ । १ । ३२ । सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । 'प्रश्ने' किम् । 'सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम' ।

३९४० । अङ्गाप्रातिलोम्ये । ८ । १ । ३३ । अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । 'अप्रातिलोम्ये' किम् । 'अङ्ग कूजसि वृषल इदानीं ज्ञास्यसि जाल्म' । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ।

३९४१ । हि च । ८ । १ । ३४ । हियुक्तं तिङन्तं नानुदात्तम् । 'आ हि ष्मा याति' । 'आ हि रुहन्तम्' ।

३९४२ । छन्दस्यनेकमपि साकाङ्क्षम् । ८ । १ । ३५ । हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । 'अनृतं हि मत्तो वदति' । 'पाप्मा चैनं पुनाति' । तिङन्तद्वयमपि न निहन्यते ।

३९४३ । यावद्यथाभ्याम् । ८ । १ । ३६ । आभ्यां योगे तिङन्तं नानुदात्तम् । 'यथा चित्कण्वमावतम्' ।

३९४४ । पूजायां नानन्तरम् । ८ । १ । ३७ । यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । 'पूजायाम्' किम् । यावद्भुङ्क्ते । 'अनन्तरम्' किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ।

३९४५ । उपसर्गव्यपेतं च । ८ । १ । ३८ । पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रपचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ।

३९४६ । तुपश्यपश्यताहैः पूजायाम् । ८ । १ । ३९ । एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । 'आदह स्वधामनु पुनर्गर्भत्वमेरिरे' ।

३९४७ । अहो च । ८ । १ । ४० । एतद्योगे नानुदात्तं पूजायाम् । अहो देवदत्तः पचति शोभनम् ।

३९४८ । शेषे विभाषा । ८ । १ । ४१ । अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ।

३९४९ । पुरा च परीप्सायाम् । ८ । १ । ४२ । पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् । अधीष्व माणवक पुरा विद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः । 'परीप्सायाम्' किम् । न ते स्म पुराधीयते । चिरातीतेऽत्र पुरा ।

३९५० । नन्वित्यनुज्ञैषणायाम् । ८ । १ । ४३ । नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । 'अनु–' इति किम् । अकार्षीः कटं त्वम् । ननु करोमि । पृष्ठप्रतिवचनमेतत् ।

३९५१ । किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् । ८ । १ । ४४ । क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् । किं द्विजः पचत्याहोस्विद्गच्छति । 'क्रिया–' इति किम् । साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । 'प्रश्ने' किम् । किं पठति । क्षेपोऽयम् । 'अनुपसर्गम्' किम् । किं प्रपचति उत प्रकरोति । 'अप्रतिषिद्धम्' किम् । किं द्विजो न पचति ।

३९५२ । लोपे विभाषा । ८ । १ । ४५ । किमोऽप्रयोग उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ।

३९५३ । एहिमन्ये प्रहासे लृट् । ८ । १ । ४६ । एहिमन्य इत्यनेन युक्तं लृडन्तं नानुदात्तं क्रीडायाम् । एहि मन्ये भक्तं भोक्ष्यसे भुक्तं तत्त्वातिथिभिः । 'प्रहासे' किम् । एहि मन्यसे ओदनं भोक्ष्य इति सुष्ठु मन्यसे । गत्यर्थलोटा लृट्–' (सू३९९८) इत्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । 'एहि मन्यसे ओदनं भोक्ष्ये' ।

३९५४ । जात्वपूर्वम् । ८ । १ । ४७ । अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । 'अपूर्वम्' किम् । कटं जातु करिष्यसि ।

३९५५ । किंवृत्तं च चिदुत्तरम् । ८ । १ । ४८ । अविद्यमानपूर्वं चिदुत्तरं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किं वृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । 'चिदुत्तरम्' किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ।

३९५६। आहो उताहो चानन्तरम्। ८।१।४९। आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम्। आहो उताहो वा भुङ्क्ते। अनन्तरमित्येव। शेषे विभाषां वक्ष्यति। 'अपूर्व-' इति किम्। देव आहो भुङ्क्ते।

३९५७। शेषे विभाषा। ८।१।५०। आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम्। आहो देवः पचति।

३९५८। गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत्। ८।१।५१। गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तम्। यत्रैव कारके लोट् तत्रैव लृडपि चेत्। आगच्छ देव ग्रामं द्रक्ष्यसि। उह्यन्तां देवदत्तेन शालयः। रामेण भोक्ष्यन्ते। 'गत्यर्थ-' किम्। पच देव ओदनं भोक्ष्यसेऽन्नम्। 'लोटा' किम्। आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम्। 'लृट्' किम्। आगच्छ देव देव ग्रामं पश्यस्येनम्। 'न चेत्' इति किम्। आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते। 'सर्वम्' किम्। आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात्। यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते।

३९५९। लोट् च। ८।१।५२। लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम्। आगच्छ देव ग्रामं पश्य। 'गत्यर्थ-' इति किम्। पच देवौदनं भुङ्क्ष्वैनम्। 'लोट्' किम्। आगच्छ देव ग्रामं पश्यसि। न चेत्कारकं सर्वान्यदित्येव। आगच्छ देव ग्रामं पश्यत्वेनं रामः। सर्वग्रहणात्त्विह स्यादेव। आगच्छ देव ग्रामं त्वं चाहं च पश्यावः। योगविभाग उत्तरार्थः।

३९६०। विभाषितं सोपसर्गमनुत्तमम्। ८।१।५३। लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम्। आगच्छ देव ग्रामं प्रविश। 'सोपसर्गम्' किम्। आगच्छ देव ग्रामं पश्य। 'अनुत्तमम्' किम्। आगच्छानि देव ग्रामं प्रविशानि।

३९६१। हन्त च। ८।१।५४। हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम्। हन्त प्रविश। सोपसर्गमित्येव। हन्त कुरु। 'निपातैर्यद्यदि-' (सू ३९३७) इति निघातप्रतिषेधः। 'अनुत्तमम्' किम्। हन्त प्रभुनजावहै।

३९६२। आम एकान्तरमामन्त्रितमनन्तिके। ८।१।५५। आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम्। आम् पचसि देवदत्त ३। 'एकान्तरम्' किम्। आम्प्रपचसि देवदत्त ३। 'आमन्त्रितम्' किम्। आम्पचति देवदत्तः। 'अनन्तिके' किम्। आम्पचसि देवदत्त।

३९६३। यद्धितुपरं छन्दसि। ८।१।५६। तिङन्तं नानुदात्तम्। 'उदसृजो यदङ्गिरः'। 'उशन्ति हि'। आख्यास्यामि तु ते। 'निपातैर्यद्-' (सू ३९३७) इति 'हि च' (सू ३९४१) इति 'तुपश्य-' (सू ३९४६) इति च सिद्धे नियमार्थमिदम्। एतैरेव परभूतैर्योगे नान्यैरिति। जाये स्वारोहावैहि। एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति।

३९६४। चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः। ८।१।५७। एषु षट्सु परतस्तिङन्तं नानुदात्तम्। देवः पचति चन। देवः पचति चित्। देवः पचतीव। देवः पचति गोत्रम्। देवः पचतिकल्पम्। देवः पचतिपचति। 'अगतेः' किम्। देवः प्रपचति चन।

३९६५। चादिषु च।८।१।५८। चवाहहैवेषु परेषु तिङन्तं नानुदात्तम्। देवः पचति च खादति च। अगतेरित्येव। देवः प्रपचति च प्रखादति च। प्रथमस्य 'चवायोगे-' (सू ३९६६) इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव।

३९६६। चवायोगे प्रथमा।८।१।५९। चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता। गाश्च चारयति वीणां वा वादयति। 'इतो वा सातिमीमहे'। उत्तरवाक्ययोरनुषज्जनीयतिङन्तापेक्षयेयं प्राथमिकी। 'योगे' किम्। पूर्वभूतयोरपि योगेऽनिघातार्थम्। प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत्।

३९६७। हेति क्षियायाम्।८।१।६०। हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता धर्मव्यतिक्रमे। स्वयं ह रथेन याति ३। उपाध्यायं पदातिं गमयति। 'क्षियाशीः-' (सू ३६३३) इति प्लुतः।

३९६८। अहेति विनियोगे च।८।१।६१। अहयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता नानाप्रयोजने नियोगे क्षियायां च। त्वमह ग्रामं गच्छ। त्वमह रथेनारण्यं गच्छ। क्षियायां स्वयमह रथेन याति ३। उपाध्यायं पदातिं नयति।

३९६९। चाहलोप एवेत्यवधारणम्।२।१।६२। 'च' 'अह' एतयोर्लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता। देव एव ग्रामं गच्छतु। देव एवारण्यं गच्छतु। ग्राममरण्यं च गच्छत्वित्यर्थः। देव एव ग्रामं गच्छतु। राम एवारण्यं गच्छतु। ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थः। इहाहलोपः स च केवलार्थः। 'अवधारणम्' किम्। देव क्वेव भोक्ष्यसे। न क्वचिदित्यर्थः। अनवक्लृप्तावेव।

३९७०। चादिलोपे विभाषा।८।१।६३। चवाहहैवानां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता। चलोपे। 'इन्द्र वाजेषु नोऽव'। शुक्ला व्रीहयो भवन्ति। श्वेता गा आज्याय दुहन्ति। वालोपे। व्रीहिभिर्यजेत। यवैर्यजेत।

३९७१। वैवावेति च च्छन्दसि।८।१।६४। 'अहर्वै देवानामासीत्'। 'अयं वाव हस्त आसीत्'।

३९७२। एकान्याभ्यां समर्थाभ्याम्।८।१।६५। आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि। 'अजामेकां जिन्वति'। 'प्रजामेकां रक्षति'। 'तयोरन्यः पिप्पलं स्वाद्वत्ति'। 'समर्थाभ्याम्' किम्। एको देवानुपातिष्ठत्। एक इति संख्यापरं नान्यार्थम्।

३९७३। यद्वृत्तान्नित्यम्।८।१।६६। यत्र पदे यच्छब्दस्ततः परं तिङन्तं नानुदात्तम्। यो भुङ्क्ते। यदद्र्यङ्वायुर्वाति। अत्र 'व्यवहिते कार्यमिष्यते'।

३९७४। पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः।८।१।६७। पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम्। काष्ठाध्यापकः। 'मलोपश्च वक्तव्यः' (वा ४७३९)। दारुणाध्यापकः। अज्ञाताध्यापकः। समासान्तोदात्तत्वापवादः। 'एतत्समास इष्यते'। नेह। दारुणमध्यपाक इति वृत्तिमतम्। पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलार्थम्। एतदेव ज्ञापकम् 'अत्रप्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयते' इति।

३९७५। सगतिरपि तिङ्।८।१।६८। पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम्। यत्काष्ठं प्रपचति। 'तिङ्ङतिङः' (सू ३९३५) इति निघातस्य 'निपातैर्यत्-'

(सू ३९३७) इति निषेधे प्राप्ते विधिरयम्। सगतिग्रहणाच्च गतिरपि निहन्यते। 'गतिग्रहण उपसर्गग्रहणमिष्यते' (वा ४७३२)। नेह। यत्काष्ठं शुक्लीकरोति।

३९७६। कुत्सने च सुप्यगोत्रादौ। ८। १। ६९। कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः। पचति पूति। प्रपचति पूति। पचति मिथ्या। 'कुत्सने' किम्। प्रपचति शोभनम्। 'सुपि' किम्। पचति क्लिश्नाति। 'अगोत्रादौ' किम्। पचति गोत्रम्। 'क्रियाकुत्सन इति वाच्यम्' (वा ४७३९)। कर्तुः कुत्सने मा भूत्। पचति पूतिर्देवदत्तः। 'पूतिश्चानुबन्ध इति वाच्यम्' (वा ४७४१)। तेनायं चकारानुबन्धत्वादन्तोदात्तः। 'वा बह्वर्थमनुदात्तमिति वाच्यम्' (वा ४७४२)। पचन्तिपूति।

३९७७। गतिर्गतौ। ८। १। ७०। अनुदात्तः। अभ्युद्धरति। 'गतिः' किम्। दत्तः पचाति। 'गतौ' किम्। 'आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः'।

३९७८। तिङि चोदात्तवति। ८। १। ७१। गतिरनुदात्तः। यत्प्रपचति। तिङ्ग्रहणमुदात्तवतः परिमाणार्थम्। अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात्प्रत्यये न स्यात्। 'उदात्तवति' किम्। प्रपचति।

इति तिङन्तस्वराः।

अथ वैदिकवाक्येषु स्वरसंचारप्रकारः कथ्यते—'अग्निमीळे' इति प्रथमर्क्। तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष–' (फिट् १) इत्यन्तोदात्त इति माधवः। वस्तुतस्तु घृतादित्वात्। व्युत्पत्तौ तु निप्रत्ययस्वरेण। अम्सुप्त्वादनुदात्तः। 'अमि पूर्वः' (सू १९४) इत्येकादेशस्तु 'एकादेश उदात्तेन–' (सू ३६९८) इत्युदात्तः। ईळे। 'तिङ्ङतिङः' (सू ३९३९)इति निघातः। संहितायां तु 'उदात्तादनुदात्तस्य–' (सू ३६६०) इतीकारः स्वरितः। 'स्वरितात्संहितायाम्–' (सू ३६६८) इति 'ळे' इत्यस्य प्रचयापरपर्याया एकश्रुतिः। पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्–'(१९७५) इत्यसिप्रत्ययस्वरात्। हितशब्दोऽपि धाञो निष्ठायां 'दधातेर्हिः' (सू३०७६) इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः। 'पुरोऽव्ययम्' (सू ७६८) इति गतिसंज्ञायां 'कुगति–' (सू ७६१) इति समासे समासान्तोदात्ते 'तत्पुरुषे तुल्यार्थ–' (सू ३७३६) इत्यव्ययपूर्वपदप्रकृतिस्वरे 'गतिकारकोपपदात्कृत्' (सू ३८७३) इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते 'गतिरनन्तरः' (सू ३७८३) इति पूर्वपदप्रकृतिस्वरः। पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते 'उदात्तस्वरितपरस्य सन्नतरः' (सू३६६९) इत्यनुदात्ततरः। यज्ञस्य। नङः प्रत्ययस्वरः। विभक्तेः सुप्त्वादनुदात्तत्वे स्वरितत्वम्। देवम्। पचाद्यच्। फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः। ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः। होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। रत्नशब्दो 'नब्विषयस्य' (फिट् २६) इत्याद्युदात्तः। रत्नानि दधातीति रत्नधाः। समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः। तमपः पित्त्वादनुदात्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम्।

इति स्वरप्रकरणम्।

इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम्।
तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः॥

॥ वैयाकरणसिद्धान्तकौमुदी ॥

अथ लिङ्गानुशासनप्रकरणम् ।

१ 'लिङ्गम्' । २ 'स्त्री' । अधिकारसूत्रे एते । ३ 'ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः' । ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः । स्वस्रादिपञ्चकस्यैव ङीन्निषेधेन कर्त्रीत्यादेर्ङीपेकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोर्ऋदन्तत्वाभावात् । ४ 'अन्यूप्रत्ययान्तो धातुः' । अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । अवनिः । चमूः । 'प्रत्ययग्रहणम्' किम् । देवयतेः क्विप् । द्यूः । विशेष्यलिङ्गः । ५ 'अशनिभरण्यरणयः पुंसि च' । इयमयं वाशनिः । ६ 'मिन्यन्तः' । मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात् । भूमिः । ग्लानिः । ७ 'वह्निवृष्ण्यग्नयः पुंसि' । पूर्वस्यापवादः । ८ 'श्रोणियोन्यूर्मयः पुंसि च' । इयमयं वा श्रोणिः । ९ 'क्तिन्नन्तः' । स्पष्टम् । कृतिरित्यादि । १० 'ईकारान्तश्च' । ईप्रत्ययान्तः स्त्री स्यात् । लक्ष्मीः । ११ 'ऊङाबन्तश्च' । कुरूः । विद्या । १२ 'य्वन्तमेकाक्षरम्' । श्रीः । भूः । 'एकाक्षरम्' किम् । पृथुश्रीः । १३ 'विंशत्यादिरानवतेः' । इयं विंशतिः । त्रिंशत् । चत्वारिंशत् । पञ्चाशत् । षष्टिः । सप्ततिः । अशीतिः । नवतिः । १४ 'दुन्दुभिरक्षेषु' । इयं दुन्दुभिः । 'अक्षेषु' किम् । अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः । १५ 'नाभिरक्षत्रिये' । इयं नाभिः । १६ 'उभावप्यन्यत्र पुंसि' । दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः । नाभिः क्षत्रियः । कथं तर्हि 'समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिः' इति भारविः । उच्यते । दृढं भक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम् । वस्तुतस्तु 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति भाष्यात्पुंस्त्वमपीह साधु । अत एव 'नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान्' । 'द्वयोः प्राणिप्रतीके स्यात्स्त्रियां कस्तूरिकामदे' इति मेदिनी । रभसोऽप्याह—'मुख्यराट्क्षत्रिये नाभिः पुंसि प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे' इति । एवमेवंविधेऽन्यत्रापि बोध्यम् । १७ 'तलन्तः' । अयं स्त्रियां स्यात् । शुक्लस्य भावः शुक्लता । ब्राह्मणस्य कर्म ब्राह्मणता । ग्रामस्य समूहो ग्रामता । देव एव देवता । १८ 'भूमिविद्युत्सरिल्लतावनिताभिधानानि' । भूमिर्भूः । विद्युत्सौदामनी । सरिन्निम्नगा । लता वल्ली । वनिता योषित् । १९ 'यादो नपुंसकम्' । यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात् । २० 'भाःस्रुक्स्रग्दिगुष्णिगुपानहः' । एते स्त्रियां स्युः । इयं भाः इत्यादि । २१ 'स्थूणोर्णे नपुंसके च' । एते स्त्रियां क्लीबे च स्तः । स्थूणा-स्थूणम् । ऊर्णा-ऊर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम । २२ 'गृहशशाभ्यां क्लीबे' । नियमार्थमिदम् । गृहशशपूर्वे स्थूणोर्णे यथासंख्यं नपुंसके स्तः । गृहस्थूणम् । 'शशोर्णं शशलोमनि' इत्यमरः । २३ 'प्रावृड्विप्रुड्रुट्तृट्विट्त्विषः' । एते स्त्रियां स्युः । २४ 'दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकटयङ्गुलयः' । एते स्त्रियां स्युः । पक्षे ङीप् । दर्वी-दर्विरित्यादि । २५ 'तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः' । एते प्राग्वत् । इयं तिथिरित्यादि । अमरस्त्वाह-'तिथयो द्वयोः' इति । तथा च भारविः-'तस्य भुवि बहुतिथास्तिथयः' इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च-'निखिलां निशि पौर्णमातिथीन्' इति । २६ 'शष्कुलिरा-

जिकुटचशनिर्वातिंधुकुटित्रुटिवलिपङ्क्तयः' । एतेऽपि स्त्रियां स्युः । इयं शष्कुलिः । २७
'प्रतिपदापद्विपत्संपच्छरत्संसत्परिषदुषःसंवित्क्षुत्पुन्मुत्समिधः' । इयं प्रतिपदित्यादि । उषा
उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता । २८ 'आशीर्धूःपूर्गीर्द्वारः' । इयमाशीरित्यादि । २९
'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' । अबादीनां पञ्चानां स्त्रीत्वं स्याद्बहुत्वं च । आप
इमाः । 'स्त्रियः सुमनसः पुष्पम्' । 'सुमना मालती जातिः' । देववाची तु पुंस्येव । 'सुपर्वाणः
सुमनसः' । बहुत्वं प्रायिकम् । 'एका च सिकता तैलदानेऽसमर्था' इत्यर्थवत्सूत्रे भाष्यप्रयो-
गात् । 'समांसमां विजायते' (सू १८१३) इत्यत्र 'समायां समायाम्' इति भाष्याच्च । 'विभा-
षा घ्राधेट्–' (सू २३७६) इति सूत्रे 'अघ्रासातां सुमनसौ' इति वृत्तिव्याख्यायां हरदत्तो-
ऽप्येवम् । ३० 'स्रक्त्वक्ज्योग्वाग्यवागूनौस्फिचः' । इयं स्रक्त्वक्ज्योक्वाक्यवागूः नौ
स्फिक् । ३१ 'तृटिसीमासंबध्याः' । इयं तृटिः सीमासंबध्या । ३२ 'चुल्लिवेणिखार्यश्च' ।
स्पष्टम् । ३३ 'ताराधाराज्योत्स्नादयश्च' । 'शलाका स्त्रियां नित्यम्' । नित्यग्रहणमन्येषां क्वाचि-
द्व्यभिचारं ज्ञापयति । इति स्त्र्यधिकारः ।

३४ 'पुमान्' । अधिकारोऽयम् । ३५ 'घञबन्तः' । पाकः । त्यागः । करः । गरः
भावार्थ एवेदम् । नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नादिभिर्बाधेन
परिशेषात् । कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम्–'संबन्ध-
मनुवर्तिष्यते' इति । ३६ 'घाजन्तश्च' । विस्तरः । गोचरः । चयः । जयः इत्या-
दि । ३७ 'भयलिङ्गभगपदानि नपुंसके' । एतानि नपुंसके स्युः । भयम् । लिङ्गम् ।
भगम् । पदम् । ३८ 'नङन्तः' । नङ्प्रत्ययान्तः पुंसि स्यात् । यज्ञः । यत्नः । ३९
'याच्ञा स्त्रियाम्' । पूर्वस्यापवादः । ४० । 'क्यन्तो घुः' । किप्रत्ययान्तो घुः पुंसि स्यात् ।
आधिः । निधिः । उदधिः । 'क्यन्तः' किम् । दानम् । 'घुः' किम् । जज्ञिर्बीजम् । ४१
'इषुधिः स्त्री च' । इषुधिशब्दः स्त्रियां पुंसि च । पूर्वस्यापवादः । ४२ 'देवासुरात्मस्वर्गगिरिसमु-
द्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि' । एतानि पुंसि स्युः । देवाः सुराः । असुरा
दैत्याः । आत्मा क्षेत्रज्ञः । स्वर्गो नाकः । गिरिः पर्वतः । समुद्रोऽब्धिः । नखः कररुहः । केशः
शिरोरुहः । दन्तो दशनः । स्तनः कुचः । भुजो दोः । कण्ठो गलः । खड्गः करवालः । शरो
मार्गणः । पङ्कः कर्दम इत्यादि । ४३ 'त्रिविष्टपत्रिभुवने नपुंसके' । स्पष्टम् । तृतीयं विष्टपं त्रि-
विष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्तेऽयमारम्भः । ४४ 'द्यौः स्त्रियाम्' । द्योदिवोस्तन्त्रेणो-
पादानमिदम् । ४५ 'इषुबाहू स्त्रियां च' । चात्पुंसि । ४६ 'बाणकाण्डौ नपुंसके च' । चात्पुंसि ।
त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः । ४७ 'नन्तः' । अयं पुंसि । राजा । तक्षा ।
न च चर्मवर्मादिष्वतिव्याप्तिः । 'मन्द्व्यच्कोऽकर्तरि' इति नपुंसकप्रकरणे वक्ष्यमाणत्वात् ।
४८ 'क्रतुपुरुषकपोलगुल्फमेघाभिधानानि' । क्रतुरध्वरः । पुरुषो नरः । कपोलो गण्डः ।
गुल्फः प्रपदः । मेघो नीरदः । ४९ 'अभ्रं नपुंसकम्' । पूर्वस्यापवादः । ५० । 'उकारान्तः' ।
अयं पुंसि स्यात् । प्रभुः । इक्षुः । 'हनुर्हट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम् । द्वयोः
कपोलावयवे' इति मेदिनिः । 'करेणुरिभ्यां स्त्री नेभ' इत्यमरः । एवंजातीयकविशेषवच-
नानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः । उक्तं च–'लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः'
इति । एवमन्यत्रापि । ५१ 'धेनुरज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम्' । ५२ 'समासे रज्जुः

पुंसि च'। कर्कटरज्ज्वा–कर्कटरज्जुना। ९३ 'श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके'। ९४ 'वसु चार्थवाचि'। 'अर्थवाचि' इति किम्। 'वसुर्मयूखाग्निधनाधिपेषु'। ९५ 'मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च'। चात्पुंसि। अयं मद्गुः। इदं मद्गु। ९६ 'रुत्वन्तः'। मेरुः। सेतुः। ९७ 'दारुकसेरुजतुवस्तुमस्तूनि नपुंसके'। रुत्वन्त इति पुंस्त्वस्यापवादः। इदं दारु। ९८ 'सक्तुर्नपुंसके च'। चात्पुंसि। सक्तुः–सक्तु। ९९ 'प्राग्रश्मेरकारान्तः'। 'रश्मिदिवसाभिधानानि' इति वक्ष्यति ततः प्राक्। एतस्मादकारान्त इत्यधिक्रियते। ६० 'कोपधः'। कोपधोऽकारान्तः पुंसि स्यात्। स्तबकः। कल्कः। ६१ 'चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके'। पूर्वसूत्रापवादः। ६२ 'कण्ठकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डककपिटकतालकफलकपुलाकानि नपुंसके च'। चात्पुंसि। अयं कण्टकः। इदं कण्टकमित्यादि। ६३ 'टोपधः'। टोपधोऽकारान्तः पुंसि स्यात्। घटः। पटः। ६४ 'किरीटमुकुटललाटवटवीटशृङ्गाटकराटलोष्टानि नपुंसके'। किरीटमित्यादि। ६५ 'कुटकूटकपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च'। चात्पुंसि। कुटः। कुटमित्यादि। ६६ 'णोपधः'। णोपधोऽकारान्तः पुंसि स्यात्। गुणः। गणः। पाषाणः। ६७ 'ऋणलवणपर्णतोरणरणोष्णानि नपुंसके'। पूर्वसूत्रापवादः। ६८ 'कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च'। चात्पुंसि। ६९ 'थोपधः'। रथः। ७० 'काष्ठपृष्ठसिक्थोक्थानि नपुंसके'। इदं काष्ठमित्यादि। 'काष्ठा दिगर्था स्त्रियाम्'। इमाः काष्ठाः। ७१। 'तीर्थप्रोथयूथगाथामिन नपुंसके च'। चात्पुंसि। अयं तीर्थः। इदं तीर्थम्। ७२ 'नोपधः'। ७३ 'अदन्तः पुंसि'। इनः। फेनः। ७४। 'जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके'। पूर्वस्यापवादः। ७५ 'मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसंमानभवनवसनसंभावनविभावनविमानानि नपुंसके च'। चात्पुंसि। अयं मानः। इदं मानम्। ७६ 'पोपधः'। अदन्तः पुंसि। यूपः। दीपः। सर्पः। ७७ 'पापरूपोडुपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके'। इदं पापमित्यादि। ७८ 'शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च'। अयं शूर्पः। इदं शूर्पमित्यादि। ७९ 'भोपधः'। स्तम्भः। कुम्भः। ८०। 'तलभं नपुंसकम्'। पूर्वस्यापवादः। ८१ 'जृम्भं नपुंसके च'। जृम्भम्–जृम्भः। ८२ 'मोपधः'। सोमः। भीमः। ८३ 'रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके'। इदं रुक्ममित्यादि। ८४ 'संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च'। चात्पुंसि। अयं संग्रामः। इदं संग्रामम्। ८५ 'योपधः'। समयः। हयः। ८६ 'किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके'। स्पष्टम्। ८७ 'गोमयकषायमलयान्वयाव्ययानि नपुंसके च'। गोमयः–गोमयम्। ८८ 'रोपधः'। क्षुरः। अङ्कुरः। ८९ 'द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रनीरतीरदूरकृच्छ्ररन्ध्राश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रछत्राणि नपुंसके'। इदं द्वारमित्यादि। ९० 'शुक्रमदेवतायाम्'। इदं शुक्रं रेतः। ९१ चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च'। चात्पुंसि। चक्रः–चक्रमित्यादि। ९२ 'षोपधः'। वृषः। वृक्षः। ९३

'शिरीषशीर्षाम्बरीषपीयूषपुरीषाकिल्बिषकल्माषाणि नपुंसके' । ९४ 'यूषकरीषमिषविषवर्षाणि
नपुंसके च' । चात्पुंसि । अयं यूषः । इदं यूषमित्यादि । ९५ 'सोपधः' । वत्सः । वायसः ।
महानसः । ९६ पनसबिसबुससाहसानि नपुंसके' । ९७ 'चमसांसरसानिर्यासोपवासकार्पासवा-
सभासकासकांसमांसानि नपुंसके च' । इदं चमसम् । अयं चमस इत्यादि । ९८ कंसं चाप्रा-
णिनि' । 'कंसोऽस्त्री पानभाजनम्' । प्राणिनि तु । कंसो नाम कश्चिद्राजा । ९९ 'रश्मिदिवसा-
भिधानानि' । एतानि पुंसि स्युः । रश्मिर्मयूखः । दिवसो घस्रः । १०० 'दीधितिः स्त्रियाम्' ।
पूर्वस्यापवादः । १०१ 'दिनाहनी नपुंसके' । अयमप्यपवादः । १०२ 'मानाभिधानानि' ।
एतानि पुंसि स्युः । कुडवः । प्रस्थः । १०३ । 'द्रोणाढकौ नपुंसके च' । इदं द्रोणम् । अयं
द्रोणः । १०४ 'खारीमानिके स्त्रियाम्' । इयं खारी । इयं मानिका । १०५ 'दाराक्षतलाजा-
सूनां बहुत्वं च' । इमे दाराः । १०६ 'नाड्यपजनापपदानि व्रणाङ्गपदानि' । यथासंख्यं
नाड्यायुपपदानि व्रणादीनि पुंसि स्युः । अयं नाडीव्रणः । अपाङ्गः । जनपदः ।
व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वनिवृत्त्यर्थं सूत्रम् । १०७ 'मरुद्गरुत्तरदृत्विजः' । अयं
मरुत् । १०८ 'ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः' ।
एते पुंसि स्युः । अयमृषिः । १०९ 'ध्वजगजमुञ्जपुञ्जाः' । एते पुंसि । ११० 'हस्त-
कुन्तान्तव्रातवातदूतधूर्तसूतचूतमुहूर्ताः' । एते पुंसि । अमरस्तु 'मुहूर्तोऽस्त्रियाम्'
इत्याह । १११ 'षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः' । अयं
षण्डः । ११२ 'वंशांशपुरोडाशाः' । अयं वंशः । पुरो दाश्यते पुरोडाशः । कर्मणि घञ् ।
भावव्याख्यानयोः प्रकरणे 'पौरोडाशपुरोडाशात्ष्ठन्' (सू १४४९) इति विकारप्रकरणे 'व्रीहेः
पुरोडाशे' (सू १५२८) इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम् । 'पुरोडा-
शभुजामिष्टम्' इति माघः । ११३ 'ह्रदकन्दकुन्दबुद्बुदशब्दाः' । अयं ह्रदः । ११४ 'अर्घपथि-
मथ्यृभुक्षिस्तम्बनितम्बपूगाः' । अयमर्घः । ११५ 'पल्लवपल्वलकफरेफकटाहनिर्व्यूहमठमणि-
तरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्गपुङ्खाः' । अयं पल्लव इत्यादि । ११६ 'सारथ्यतिथिकु-
क्षिवस्तिपाण्यञ्जलयः' । एते पुंसि । अयं सारथिः । इति पुंलिङ्गाधिकारः ।

११७ 'नपुंसकम्' । अधिकारोऽयम् । ११८ 'भावे ल्युडन्तः' । हसनम् । 'भावे' किम् ।
पचनोऽग्निः । इध्मव्रश्चनः कुठारः । ११९ 'निष्ठा च' । भावे या निष्ठा तदन्तं क्लीबं स्यात् ।
हसितम् । गीतम् । १२० 'त्वष्यञौ तद्धितौ' । शुक्लत्वम्–शौक्ल्यम् । ष्यञः षित्त्वसामर्थ्या-
त्पक्षे स्त्रीत्वम् । चातुर्यम्–चातुरी । सामग्र्यम्–सामग्री । औचित्यम्–औचिती । १२१ 'कर्मणि
च ब्राह्मणादिगुणवचनेभ्यः' । ब्राह्मणस्य कर्म ब्राह्मण्यम् । १२२ 'यद्यढग्यगञण्वुञ्छाश्च भाव-
कर्मणि' । एतदन्तानि क्लीबानि । 'स्तेनाद्यन्नलोपश्च' (सू १७९०) । स्तेयम् । 'सख्युर्यः'
(सू १७९१) । सख्यम् । 'कपिज्ञात्योर्ढक्' (सू १७९२) । कापेयम् । 'पत्यन्तपुरोहितादिभ्यो
यक्' (सू १७९३) । आधिपत्यम् । 'प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्' (सू १७९४) । औद्गा-
त्रम् । 'हायनान्तयुवादिभ्योऽण्' (सू १७९५) । द्वैहायनम् । द्वन्द्वमनोज्ञादिभ्यो वुञ् । पितापुत्रकम् ।
'होत्राभ्यश्छः' । (सू १८००) । अच्छावाकीयम् । 'अव्ययीभावः–' (सू ६५९) । अधिस्त्रि ।
१२३ । 'द्वन्द्वैकत्वम्' । पाणिपादम् । १२४ 'अभाषायां हेमन्तशिशिरावहोरात्रे च' । स्पष्टम् ।
१२५ 'अनञ्कर्मधारयस्तत्पुरुषः' । अधिकारोऽयम् । १२६ । 'अनल्पे छाया' । शरच्छायम् ।

१२७ 'राजामनुष्यपूर्वा सभा'। इनसभमित्यादि। १२८ 'सुरासेनाच्छायाशालानिशा स्त्रियां च'। १२९ 'परवत्'। अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात्। 'रात्राह्नाहाः पुंसि' (सू ८१४)। १३० 'अपथपुण्याहे नपुंसके'। १३१ 'संख्यापूर्वा रात्रिः'। त्रिरात्रम्। 'संख्यापूर्वा' इति किम्। सर्वरात्रः। १३२ 'द्विगुः स्त्रियां च'। व्यवस्थया। पञ्चफली। त्रिभुवनम्। १३३ 'इसुसन्तः'। हविः। धनुः। १३४ 'अर्चिः स्त्रियां च'। इसन्तत्वेऽप्यर्चिः स्त्रियां नपुंसके च स्यात्। इयमिदं वार्चिः। १३५ 'छदिः स्त्रियामेव'। इयं छदिः। छाद्यतेऽननेति छदेश्रुरादिण्यन्तात् 'अर्चिशुचि-' इत्यादिना इस्। 'इस्मन्' इत्यादिना ह्रस्वः। 'पटलं छदिः' इत्यमर। तत्र पटलसाहचर्याच्छदिषः क्लीवतां वदन्तोऽमरव्याख्यातार उपेक्ष्याः। १३६ 'मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि'। एतेषामभिधायकानि क्लीबे स्युः। मुखमाननम्। नयनं लोचनम्। लोहं कालम्। वनं गहनम्। मांसमामिषम्। रुधिरं रक्तम्। कार्मुकं शरासनम्। विवरं बिलम्। जलं वारि। हलं लाङ्गलम्। धनं द्रविणम्। अन्नमशनम्। अस्यापवादानाह त्रिसूत्र्या। १३७ 'सीरार्थौदनाः पुंसि'। १३८ 'वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च'। वक्त्रो वक्त्रम्। नेत्रो नेत्रम्। अरण्योऽरण्यम्। गाण्डीवो गाण्डीवम्। १३९ 'अटवी स्त्रियाम्'। १४० 'लोपधः'। कुलम्—कूलम्। स्थलम्। १४१ 'तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि'। अयं तूलः। १४२ 'शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालबालनिगलपलालविडालखिलशूलाः पुंसि च'। चात्क्लीबे। इदं शीलमित्यादि। १४३ 'शतादिः संख्या'। शतम्। सहस्रम्। 'शतादिः' इति किम्। एको द्वौ बहवः। 'संख्या' इति किम्। शतशृङ्गो नाम पर्वतः। १४४ 'शतायुतप्रयुताः पुंसि च'। अयं शतः। इदं शतमित्यादि। १४५ 'लक्षा कोटिः स्त्रियाम्'। इयं लक्षा। इयं कोटिः। 'वा लक्षा नियुतं च तत्' इत्यमरात्क्लीबेऽपि लक्षम्। १४६ 'शङ्कुः पुंसि'। सहस्रः क्वचित्। अयं सहस्रः। इदं सहस्रम्। १४७ 'मन्द्व्यच्कोऽकर्तरि'। मन्प्रत्ययान्तो द्व्यच्कः क्लीबः स्यान्न तु कर्तरि। वर्म। चर्म। 'द्व्यच्कः' किम्। अणिमा। महिमा। 'अकर्तरि' किम्। ददाति इति दामा। १४८ 'ब्रह्मन्पुंसि च'। अयं ब्रह्मा। इदं ब्रह्म। १४९ 'नामरोमणी नपुंसके'। 'मन्द्व्यच्कः-' इत्यस्यायं प्रपञ्चः। १५० 'असन्तो द्व्यच्कः'। यशः। मनः। तपः। 'द्व्यच्कः' किम्। चन्द्रमाः। १५१ 'अप्सराः स्त्रियाम्'। एता अप्सरसः। प्रायेणायं बहुवचनान्तः। १५२ 'त्रान्तः'। पत्रम्। छत्रम्। १५३ 'यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव'। १५४ 'भृत्रामित्रछात्रपुत्रमन्त्रवृत्रमेढ्रोष्ट्राः पुंसि'। अयं भृत्रः। न मित्रममित्रः। 'तस्य मित्राण्यमित्रास्ते' इति माघः। 'स्यातामिमित्रौ मित्रे च' इति च। यत्तु 'द्विषोऽमित्रे' (सू ३११३)इति सूत्रे हरदत्तेनोक्तम्—'अमेर्द्विषदित्यौणादिक इत्रच्। अमैरमित्रं मित्रस्य व्यथयेदित्यादौ मध्योदात्तस्तु चिन्त्यः। नञ्समासेऽप्येवम्। परवल्लिङ्गतापि स्यादिति तु तत्र दोषान्तरम्' इति तत्प्रकृतसूत्रापर्यालोचनमूलकम्। स्वरदोषोद्भवनमपि 'नञो जरमरमित्रमृताः' (सू ३८५०) इति षाष्ठसूत्रास्मरणमूलकमिति दिक्। १५५ 'पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च'। १५६ 'बलकुसुमशुल्वयुद्धपत्तनरणाभिधानानि'। बलं वीर्यम्। १५७ 'पद्मकमलोत्पलानि पुंसि च'। पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः। अमरोऽप्याह—'वा पुंसि पद्मं नलिनम्' इति। एवं च 'अर्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेव' इति वृत्तिग्रन्थो मतान्तरेण

न्यः। १५८ 'आहवसंग्रामौ पुंसि'। १५९ 'आजिः स्त्रियामेव'। १६० 'फलजातिः'। फलजातिवाची शब्दो नपुंसकं स्यात्। आमलकम्। आम्रम्। १६१ 'वृक्षजातिः'। स्त्रियामेव क्वचिदेवेदम्। हरीतकी। १६२ 'वियज्जगत्सकृत्शकन्पृषच्छकृद्यकृदुदश्वितः'। एते क्लीबाः स्युः १६३ 'नवनीतावतानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि'। १६४ 'श्राद्धकुलिशदैवपीठकुण्डाङ्कदधिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्वबीजानि'। एतानि क्लीबे स्युः। १६५ 'दैवं पुंसि च'। दैवम्-दैवः। १६६ 'धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि'। इदं धान्यमित्यादि। १६७ 'द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि'। १६८ 'अक्षमिन्द्रिये'। 'इन्द्रिये' किम्। रथाङ्गादौ मा भूत्। इति नपुंसकाधिकारः।

१६९ 'स्त्रीपुंसयोः'। अधिकारोऽयम्। १७० 'गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः'। इयमयं वा गौः। १७१ 'मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः'। इयमयं वा मृत्युः। १७२ 'गुणवचनमुकारान्तं नपुंसकं च'। त्रिलिङ्गमित्यर्थः। पटु-पटुः-पट्वी १७३ 'अपत्यार्थतद्धिते'। औपगवः-औपगवी। इति स्त्रीपुंसाधिकारः।

१७४ 'पुंनपुंसकयोः'। अधिकारोऽयम्। १७५ 'घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः'। अयं घृतः। इदं घृतम्। १७६ 'शृङ्गार्घनिदाघोद्यमशल्यदृढाः'। अयं शृङ्गः। इदं शृङ्गम्। १७७ 'व्रजकुञ्जकुथकूर्चप्रस्थदर्पार्धर्चदर्भपुच्छाः'। अयं व्रजः। इदं व्रजम्। १७८ 'कबन्धौषधायुधान्ताः'। स्पष्टम्। १७९ 'दण्डमण्डखण्डशवसैन्धवपार्श्वाकाशकुशकाशाङ्कुशकुलिशाः'। एते पुंनपुंसकयोः स्युः। 'कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जले' इति विश्वः। शलाकावाची तु स्त्रियाम्। तथा च 'जानपद-' (सू ५००) आदिसूत्रेणायोविकारे ङीषि। कुशी। दारुणि तु टापा 'कुशा वानस्पत्याः स्थ ता मा यात' इति श्रुतिः। 'अतः कृकमि-' (सू १६०) इति सूत्रे 'कुशाकर्णीषु' इति प्रयोगश्च। व्याससूत्रे च-'हानौ तूपायनशब्दे शेषत्वात्कुशाच्छन्दः' इति। तत्र शारीरकभाष्येऽप्येवम्। एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थित आच्छन्द इत्याङ्प्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः। १८० गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च'। इति पुंनपुंसकाधिकारः।

१८१ 'अवशिष्टलिङ्गम्'। १८२ 'अव्ययं कतियुष्मदस्मदः'। १८३ 'ष्णान्ता संख्या'। शिष्टा परवत् एकः पुरुषः। एका स्त्री। एकं कुलम्। १८४ 'गुणवचनं च'। शुक्लः पटः। शुक्ला पटी। शुक्लं वस्त्रम्। १८५ 'कृत्याश्च'। १८६ 'करणाधिकरणयोर्ल्युट्'। १८७ 'सर्वादीनि सर्वनामानि'। स्पष्टार्थेयं त्रिसूत्री।

इति लिङ्गानुशासनप्रकरणम्।

इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरणसिद्धान्तकौमुदी समाप्ता।

॥ सिद्धान्तकौमुदीपरिशिष्टानि ॥

(१) अष्टाध्यायीसूत्रपाठः ।

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥

अइउण् । ऋलृक् । एओङ् । ऐऔच् । हयवरट् । लण् । ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव् । कपय् । शषसर् । हल् ॥ इति प्रत्याहारसूत्राणि ॥

प्रथमोऽध्यायः ।

प्रथमः पादः ।

१ वृद्धिरादैच् २६ । २ अदेङ्गुणः २७ । ३ इको गुणवृद्धी ३४ । ४ न धातुलोप
आर्धधातुके २६५६ । ५ क्ङिति च [illegible] २१९० । ७ हलोऽनन्तराः
संयोगः ३० । ८ मुखनासिकावचनो [illegible] स्यप्रयत्नं सवर्णम् १० । १०
नाज्झलौ १३ । ११ ईदूदेद्द्विवचनं [illegible] मात् १०१ । १३ शे १०२ ।
१४ निपात एकाजनाङ् १०३ । [illegible] संबुद्धौ शाकल्यस्येतावनार्षे
१०५ । १७ उञः १०६ । १८ ऊँ १० [illegible] र्थे १०९ । २० दाधा घ्वदाप्
२३७३ ॥ १ ॥ २१ आद्यन्तवदेकस्मि[illegible] घः २००३ । २३ बहुगणव-
तुडति,संख्या २५८ । २४ ष्णान्ता ष[illegible] डति च २५९ । २६ क्तक्तवतू निष्ठा
३०१२ । २७ सर्वादीनि सर्वनामानि २१[illegible] दिक्समासे बहुव्रीहौ २९२ । २९
न बहुव्रीहौ २२२ । ३० तृतीयासमासे २[illegible] । ३१ द्वन्द्वे च २२४ । ३२ विभाषा जसि २२५ ।
३३ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च २२६ । ३४ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यव-
स्थायामसंज्ञायाम् २१८ । ३५ स्वमज्ञातिधनाख्यायाम् २१९ । ३६ अन्तरं बहिर्योगोपसं-
व्यानयोः २२० । ३७ स्वरादिनिपातमव्ययम् ४४७ । ३८ तद्धितश्चासर्वविभक्तिः ४४८ । ३९
कृन्मेजन्तः ४४९ । ४० क्त्वातोसुन्कसुनः ४५० ॥ २ ॥ ४१ अव्ययीभावश्च ४५१ । ४२ शि सर्व-
नामस्थानम् ३१३ । ४३ सुडनपुंसकस्य २२९ । ४४ न वेति विभाषा २४ । ४५ इग्यणः संप्रसारणम्
३२८ । ४६ आद्यन्तौ टकितौ ३६ । ४७ मिदचोऽन्त्यात्परः ३७ । ४८ एच इग्घ्रस्वादेशे ३२३ । ४९
षष्ठी स्थानेयोगा ३८ । ५० स्थानेऽन्तरतमः ३९ । ५१ उरण्रपरः ७० । ५२ अलोऽन्त्यस्य

४२ । ५३ ङिच्च ४३ । ५४ आदेः परस्य ४४ । ५५ अनेकाल्शित्सर्वस्य ४५ । ५६ स्थानिवदादेशोऽनल्विधौ ४९ । ५७ अचः परस्मिन्पूर्वविधौ ५० । ५८ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ५१ । ५९ द्विर्वचनेऽचि २२४३ । ६० अदर्शनं लोपः ५३ ॥ ३ ॥ ६१ प्रत्ययस्य लुक्श्लुलुपः २६० । ६२ प्रत्ययलोपे प्रत्ययलक्षणम् २६२ । ६३ न लुमताङ्गस्य २६३ । ६४ अचोऽन्त्यादि टि ७९ । ६५ अलोऽन्त्यात्पूर्व उपधा २५९ । ६६ तस्मिन्निति निर्दिष्टे पूर्वस्य ४० । ६७ तस्मादित्युत्तरस्य ४१ । ६८ स्वं रूपं शब्दस्याशब्दसंज्ञा २५ । ६९ अणुदित्सवर्णस्य चाप्रत्ययः १४ । ७० तपरस्तत्कालस्य १५ । ७१ आदिरन्त्येन सहेता २ । ७२ येन विधिस्तदन्तस्य २६ । ७३ वृद्धिर्यस्याचामादिस्तद्वृद्धम् १३३५ । ७४ त्यदादीनि च १३३६ । ७५ एङ् प्राचां देशे १३३८ ॥ वृद्धिराद्यन्तवदव्ययीभावः प्रत्ययस्य लुक्पञ्चदश ॥

द्वितीयः पादः ।

१ गाङ्कुटादिभ्योऽञ्णिन्ङित् २४६१ । २ विज इट् २५३६ । ३ विभाषोर्णोः २४४७ । ४ सार्वधातुकमपित् २२३४ । ५ असंयोगाल्लिट् कित् २२४२ । ६ इन्धिभवतिभ्यां च ३३९३ । ७ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ३३२३ । ८ रुदविदमुषग्रहिस्वपिप्रच्छः संश्च २६०९ । ९ इको झल् २६१२ । १० हलन्ताच्च २६१३ । ११ लिङ्सिचावात्मनेपदेषु २३०० । १२ उश्च २३६८ । १३ वा गमः २७०० । १४ हनः सिच् २६९७ । १५ यमो गन्धने २६९८ । १६ विभाषोपयमने २७३० । १७ स्थाघ्वोरिच्च २३८९ । १८ न क्त्वा सेट् ३३२२ । १९ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ३०५२ । २० मृषस्तितिक्षायाम् ३०५५ ॥ १ ॥ २१ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ३०५६ । २२ पूङः क्त्वा च ३०५१ । २३ नोपधात्थफान्ताद्वा ३३२४ । २४ वञ्चिलुञ्च्यृतश्च ३३२५ । २५ तृषिमृषिकृशेः काश्यपस्य ३३२६ । २६ रलो व्युपधाद्धलादेः संश्च २६१७ । २७ ऊकालोऽज्झ्रस्वदीर्घप्लुतः ४ । २८ अचश्च ३५ । २९ उच्चैरुदात्तः ५ । ३० नीचैरनुदात्तः ६ । ३१ समाहारः स्वरितः ७ । ३२ तस्यादित उदात्तमर्धह्रस्वम् ८ । ३३ एकश्रुति दूरात्संबुद्धौ ३६६२ । ३४ यज्ञकर्मण्यजपन्यूङ्खसामसु ३६६३ । ३५ उच्चैस्तरां वा वषट्कारः ३६६४ । ३६ विभाषा छन्दसि ३६६५ । ३७ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ३६६६ । ३८ देवब्रह्मणोरनुदात्तः ३६६७ । ३९ स्वरितात्संहितायामनुदात्तानाम् ३६६८ । ४० उदात्तस्वरितपरस्य सन्नतरः ३६६९ ॥ २ ॥ ४१ अपृक्त एकाल्प्रत्ययः २५१ । ४२ तत्पुरुषः समानाधिकरणः कर्मधारयः ७४५ । ४३ प्रथमानिर्दिष्टं समास उपसर्जनम् ६५३ । ४४ एकविभक्ति चापूर्वनिपाते ६५५ । ४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १७८ । ४६ कृत्तद्धितसमासाश्च १७९ । ४७ ह्रस्वो नपुंसके प्रातिपदिकस्य ३१८ । ४८ गोस्त्रियोरुपसर्जनस्य ६५६ । ४९ लुक्तद्धितलुकि १४०८ । ५० इद्गोण्याः १७०३ । ५१ लुपि युक्तवद्व्यक्तिवचने १२९४ । ५२ विशेषणानां चाजातेः १३०० । ५३ तदशिष्यं संज्ञाप्रमाणत्वात् १२९५ । ५४ लुब्योगाप्रख्यानात् १२९६ । ५५ योगप्रमाणे च तदभावेऽदर्शनं स्यात् १२९७ । ५६ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् १२९८ । ५७ कालोपसर्जने च तुल्यम् १२९९ । ५८ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ८१७ । ५९ अस्मदो द्वयोश्च ८१८ । ६० फल्गुनीप्रोष्ठपदानां च नक्षत्रे ८१९ ॥ ३ ॥ ६१ छन्दसि पुनर्वस्वोरेकवचनम् ३३८७ । ६२ विशाखयोश्च

३३८८ । ६३ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ८२० । ६४ सरूपाणा-
मेकशेष एकविभक्तौ १८८ । ६५ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ९३१ । ६६ स्त्री पुंवच्च
९३२ । ६७ पुमान्स्त्रिया ९३३ । ६८ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ९३४ । ६९ नपुंसकमनपुंस-
केनैकवच्चास्यान्यतरस्याम् ९३५ । ७० पिता मात्रा ९३६ । ७१ श्वशुरः श्वश्र्वा ९३७ । ७२
त्यदादीनि सर्वैर्नित्यम् ९३८ । ७३ ग्राम्यपशुसंघेष्वतरुणेषु स्त्री ९३९ ॥ गाङ्कुटाद्युदुपधा-
द्वृक्तश्छन्दसि पुनर्वस्वोश्चत्रयोदश ॥

तृतीयः पादः ।

१ भूवादयो धातवः १८ । २ उपदेशेऽजनुनासिक इत् ३ । ३ हलन्त्यम् १ । ४ न विभ-
क्तौ तुस्माः १९० । ५ आदिर्ञिटुडवः २२८९ । ६ षः प्रत्ययस्य ४७४ । ७ चुटू १८९ । ८
लशक्वतद्धिते १९५ । ९ तस्य लोपः ६२ । १० यथासंख्यमनुदेशः समानाम् १२८ । ११
स्वरितेनाधिकारः ४६ । १२ अनुदात्तङित आत्मनेपदम् २१५७ । १३ भावकर्मणोः २६७९ ।
१४ कर्तरि कर्मव्यतिहारे २६८० । १५ न गतिहिंसार्थेभ्यः २६८१ । १६ इतरेतरान्योन्योप-
पदाच्च २६८२ । १७ नेर्विशः २६८३ । १८ परिव्यवेभ्यः क्रियः २६८४ । १९ विपराभ्यां जेः
२६८५ । २० आङो दोऽनास्यविहरणे २६८६ ॥ १ ॥ २१ क्रीडोऽनुसंपरिभ्यश्च २६८७ । २२
समवप्रविभ्यः स्थः २६८९ । २३ प्रकाशनस्थेयाख्ययोश्च २६९० । २४ उदोऽनूर्ध्वकर्मणि
२६९१ । २५ उपान्मन्त्रकरणे २६९२ । २६ अकर्मकाच्च २६९३ । २७ उद्विभ्यां तपः २६९४ ।
२८ आङो यमहनः २६९५ । २९ समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः २६९९ । ३०
निसमुपविभ्यो ह्वः २७०३ । ३१ स्पर्धायामाङः २७०४ । ३२ गन्धनावक्षेपणसेवनसाहसिक्य-
प्रतियत्नप्रकथनोपयोगेषु कृञः २७०५ । ३३ अधेः प्रसहने २७०६ । ३४ वेः शब्दकर्मणः
२७०७ । ३५ अकर्मकाच्च २७०८ । ३६ संमाननोत्संजनाचार्यकरणज्ञानभृतिविगणनव्ययेषु
नियः २७०९ । ३७ कर्तृस्थे चाशरीरे कर्मणि २७१० । ३८ वृत्तिसर्गतायनेषु क्रमः २७११ ।
३९ उपपराभ्याम् २७१२ । ४० आङ उद्गमने २७१३ ॥ २ ॥ ४१ वेः पादविहरणे २७१४ ।
४२ प्रोपाभ्यां समर्थाभ्याम् २७१५ । ४३ अनुपसर्गाद्वा २७१६ । ४४ अपह्नवे ज्ञः २७१७ ।
४५ अकर्मकाच्च २७१८ । ४६ संप्रतिभ्यामनाध्याने २७१९ । ४७ भासनोपसंभाषाज्ञानयत्न-
विमत्युपमन्त्रणेषु वदः २७२० । ४८ व्यक्तवाचां समुच्चारणे २७२१ । ४९ अनोरकर्मकात्
२७२२ । ५० विभाषा विप्रलापे २७२३ । ५१ अवाद्ग्रः २७२४ । ५२ समः प्रतिज्ञाने २७२५ ।
५३ उदश्चरः सकर्मकात् २७२६ । ५४ समस्तृतीयायुक्तात् २७२७ । ५५ दाणश्च सा चेच्च-
तुर्थ्यर्थे २७२८ । ५६ उपाद्यमः स्वकरणे २७२९ । ५७ ज्ञाश्रुस्मृदृशां सनः २७३१ । ५८ ना-
नोर्ज्ञः २७३२ । ५९ प्रत्याङ्भ्यां श्रुवः २७३३ । ६० शदेः शितः २३६२ ॥ ३ ॥ ६१ म्रिय-
तेर्लुङ्लिङोश्च २५३८ । ६२ पूर्ववत्सनः २७३४ । ६३ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य २२४० ।
६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु २७३५ । ६५ समः क्ष्णुवः २७३६ । ६६ भुजोऽनवने २७३७ ।
६७ णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने २७३८ । ६८ भीस्म्योर्हेतुभये २५९४ । ६९ गृधिव-
ञ्च्योः प्रलम्भने २७३९ । ७० लियः संमाननशालीनीकरणयोश्च २५९२ । ७१ मिथ्योपपदा-
त्कृञोऽभ्यासे २७४० । ७२ स्वरितञितः कर्त्रभिप्राये क्रियाफले २१५८ । ७३ अपाद्वदः
२७४१ । ७४ णिचश्च २५६४ । ७५ समुदाङ्भ्यो यमोऽग्रन्थे २७४२ । ७६ अनुपसर्गाज्ज्ञः

२७४३ । ७७ विभाषोपपदेन प्रतीयमाने २७४४ । ७८ शेषात्कर्तरि परस्मैपदम् २१५९ । ७९ अनुपराभ्यां कृञः २७४५ । ८० अभिप्रत्यतिभ्यः क्षिपः २७४६ ॥ ४ ॥ ८१ प्राद्वहः २७४७ । ८२ परेर्मृषः २७४८ । ८३ व्याङ्परिभ्यो रमः २७४९ । ८४ उपाच्च २७५० । ८५ विभाषाऽकर्मकात् २७५१ । ८६ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः २७५२ । ८७ निगरणचलनार्थेभ्यश्च २७५३ । ८८ अणावकर्मकाच्चित्तवत्कर्तृकात् २७५४ । ८९ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः २७५५ । ९० वा क्यषः २६६९ । ९१ द्युद्भ्यो लुङि २३४५ । ९२ वृद्भ्यः स्यसनोः २३४७ । ९३ लुटि च क्लृपः २३५१ ॥ भूवादयः क्रीडोऽनु वेः पादम्रियतेः प्राद्वहश्चयोदश ॥

चतुर्थः पादः ।

१ आ कडारादेका संज्ञा २३२ । २ विप्रतिषेधे परं कार्यम् १७५ । ३ यू स्त्र्याख्यौ नदी २६६ । ४ नेयङुवङ्स्थानावस्त्री ३०३ । ५ वामि ३०४ । ६ ङिति ह्रस्वश्च २९६ । ७ शेषो घ्यसखि २४३ । ८ पतिः समास एव २५७ । ९ षष्ठीयुक्तश्छन्दसि वा ३३८९ । १० ह्रस्वं लघु ३१ । ११ संयोगे गुरु ३२ । १२ दीर्घं च ३३ । १३ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् १९९ । १४ सुप्तिङन्तं पदम् २९ । १५ नः क्ये २६५९ । १६ सिति च ३२५२ । १७ स्वादिष्वसर्वनामस्थाने २३० । १८ यचि भम् २३१ । १९ तसौ मत्वर्थे १८९६ । २० अयस्मयादीनि छन्दसि ३३९० ॥ १ ॥ २१ बहुषु बहुवचनम् १८७ । २२ द्व्येकयोर्द्विवचनैकवचने १८६ । २३ कारके ५३४ । २४ ध्रुवमपायेऽपादानम् ५८६ । २५ भीत्रार्थानां भयहेतुः ५८८ । २६ पराजेरसोढः ५८९ । २७ वारणार्थानामीप्सितः ५९० । २८ अन्तर्धौ येनादर्शनमिच्छति ५९१ । २९ आख्यातोपयोगे ५९२ । ३० जनिकर्तुः प्रकृतिः ५९३ । ३१ भुवः प्रभवः ५९४ । ३२ कर्मणा यमभिप्रैति स संप्रदानम् ५६९ । ३३ रुच्यर्थानां प्रीयमाणः ५७१ । ३४ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ५७२ । ३५ धारेरुत्तमर्णः ५७३ । ३६ स्पृहेरीप्सितः ५७४ । ३७ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ५७५ । ३८ क्रुधद्रुहोरुपसृष्टयोः कर्म ५७६ । ३९ राधीक्ष्योर्यस्य विप्रश्नः ५७७ । ४० प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ५७८ ॥ २ ॥ ४१ अनुप्रतिगृणश्च ५७९ । ४२ साधकतमं करणम् ५६० । ४३ दिवः कर्म च ५६२ । ४४ परिक्रयणे संप्रदानमन्यतरस्याम् ५८० । ४५ आधारोऽधिकरणम् ६३२ । ४६ अधिशीङ्स्थासां कर्म ५४२ । ४७ अभिनिविशश्च ५४३ । ४८ उपान्वध्याङ्वसः ५४४ । ४९ कर्तुरीप्सिततमं कर्म ५३५ । ५० तथायुक्तं चानीप्सितम् ५३८ । ५१ अकथितं च ५३९ । ५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ ५४० । ५३ हृक्रोरन्यतरस्याम् ५४१ । ५४ स्वतन्त्रः कर्ता ५५९ । ५५ तत्प्रयोजको हेतुश्च २५७५ । ५६ प्राग्रीश्वरान्निपाताः १९ । ५७ चादयोऽसत्त्वे २० । ५८ प्रादयः २१ । ५९ उपसर्गाः क्रियायोगे २२ । ६० गतिश्च २३ ॥ ३ ॥ ६१ ऊर्यादिच्विडाचश्च ७६२ । ६२ अनुकरणं चानितिपरम् ७६३ । ६३ आदरानादरयोः सदसती ७६४ । ६४ भूषणेऽलम् ७६५ । ६५ अन्तरपरिग्रहे ७६६ । ६६ कणेमनसी श्रद्धाप्रतीघाते ७६७ । ६७ पुरोऽव्ययम् ७६८ । ६८ अस्तं च ७६९ । ६९ अच्छ गत्यर्थवदेषु ७७० । ७० अदोऽनुपदेशे ७७१ । ७१ तिरोऽन्तर्धौ ७७२ । ७२ विभाषा कृञि ७७३ । ७३ उपाजेऽन्वाजे ७७४ । ७४ साक्षात्प्रभृतीनि च ७७५ । ७५ अनत्याधान उरसिमनसी ७७६ । ७६ मध्येपदेनिवचने च ७७७ । ७७ नित्यं हस्तेपाणावुपयमने ७७८ ।

७८ प्राध्वं बन्धने ७७९ | ७९ जीविकोपनिषदावौपम्ये ७८० | ८० ते प्राग्धातोः २२३०
॥४॥ ८१ छन्दसि परेऽपि ३३९१ | ८२ व्यवहिताश्च ३३९२ | ८३ कर्मप्रवचनीयाः ५४६ |
८४ अनुर्लक्षणे ५४७ | ८५ तृतीयार्थे ५४९ | ८६ हीने ५५० | ८७ उपोऽधिके च ५५१ |
८८ अपपरी वर्जने ५९६ | ८९ आङ्मर्यादावचने ५९७ | ९० लक्षणेत्थंभूताख्यानभागवी-
प्सासु प्रतिपर्यनवः ५५२ | ९१ अभिरभागे ५५३ | ९२ प्रतिः प्रतिनिधिप्रतिदानयोः ५९९ |
९३ अधिपरी अनर्थकौ ५५४ | ९४ सुः पूजायाम् ५५५ | ९५ अतिरतिक्रमणे च ५५६ |
९६ अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु ५५७ | ९७ अधिरीश्वरे ६४४ | ९८
विभाषा कृञि ६४६ | ९९ लः परस्मैपदम् २१५५ | १०० तङानावात्मनेपदम् २१५६ |
५ ॥ १०१ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः २१६० | १०२ तान्येकवचनद्विवचनबहुव-
चनान्येकशः २१६१ | १०३ सुपः १८५ | १०४ विभक्तिश्च १८४ | १०५ युष्मद्युपपदे
समानाधिकरणे स्थानिन्यपि मध्यमः २१६२ | १०६ प्रहासे च मन्योपपदे मन्यतेरुत्तम
एकवच्च २१६३ | १०७ अस्मद्युत्तमः २१६४ | १०८ शेषे प्रथमः २१६५ | १०९ परः
संनिकर्षः संहिता २८ | ११० विरामोऽवसानम् २७ ॥ आ कडाराद्बहुष्वनुप्रतिगृण ऊर्या-
दिच्छन्दसि तिङो दश ॥

इति प्रथमोऽध्यायः ।

द्वितीयोऽध्यायः ।

प्रथमः पादः ।

१ समर्थः पदविधिः ६४७ | २ सुबामन्त्रिते पराङ्गवत्स्वरे ३६५६ | ३ प्राक्कडारात्समासः
६४८ | ४ सह सुपा ६४९ | ५ अव्ययीभावः ६५१ | ६ अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्य-
र्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु
६५२ | ७ यथासादृश्ये ६६१ | ८ यावदवधारणे ६६२ | ९ सुप्प्रतिना मात्रार्थे ६६३ | १०
अक्षशलाकासंख्याः परिणा ६६४ | ११ विभाषा ६६५ | १२ अपपरिबहिरञ्चवः पञ्चम्या
६६६ | १३ आङ्मर्यादाभिविध्योः ६६७ | १४ लक्षणेनाभिप्रती आभिमुख्ये ६६८ | १५
अनुर्यत्समया ६६९ | १६ यस्य चायामः ६७० | १७ तिष्ठद्गुप्रभृतीनि च ६७१ | १८ पारे
मध्ये षष्ठ्या वा ६७२ | १९ संख्या वंश्येन ६७३ | २० नदीभिश्च ६७४ ॥ १ ॥ २१ अन्य-
पदार्थे च संज्ञायाम् ६७५ | २२ तत्पुरुषः ६८४ | २३ द्विगुश्च ६८५ | २४ द्वितीया श्रिता-
तीतपतितगतात्यस्तप्राप्तापन्नैः ६८६ | २५ स्वयं क्तेन ६८७ | २६ खट्वा क्षेपे ६८८ | २७
सामि ६८९ | २८ कालाः ६९० | २९ अत्यन्तसंयोगे च ६९१ | ३० तृतीया तत्कृतार्थेन
गुणवचनेन ६९२ | ३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ६९३ | ३२ कर्तृकरणे
कृता बहुलम् ६९४ | ३३ कृत्यैरधिकार्थवचने ६९५ | ३४ अन्नेन व्यञ्जनम् ६९६ | ३५
भक्ष्येण मिश्रीकरणम् ६९७ | ३६ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ६९८ | ३७ पञ्चमी
भयेन ६९९ | ३८ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ७०० | ३९ स्तोकान्तिकदूरार्थ-
कृच्छ्राणि क्तेन ७०१ | ४० सप्तमी शौण्डैः ७१७ ॥ २ ॥ ४१ सिद्धशुष्कपक्वबन्धैश्च ७१८ |
४२ ध्वाङ्क्षेण क्षेपे ७१९ | ४३ कृत्यैर्ऋणे ७२० | ४४ संज्ञायाम् ७२१ | ४५ क्तेनाहोरात्रा-

वयवाः ७२२ । ४६ तत्र ७२३ । ४७ क्षेपे ७२४ । ४८ पात्रेसमितादयश्च ७२५ । ४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ७२६ । ५० दिक्संख्ये संज्ञायाम् ७२७ । ५१ तद्धितार्थोत्तरपदसमाहारे च ७२८ । ५२ संख्यापूर्वो द्विगुः ७३० । ५३ कुत्सितानि कुत्सनैः ७३२ । ५४ पापाणके कुत्सितैः ७३३ । ५५ उपमानानि सामान्यवचनैः ७३४ । ५६ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ७३५ । ५७ विशेषणं विशेष्येण बहुलम् ७३६ । ५८ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ७३७ । ५९ श्रेण्यादयः कृतादिभिः ७३८ । ६० क्तेन नञ्विशिष्टेनानञ् ७३९ ॥ ३ ॥ ६१ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ७४० । ६२ वृन्दारकनागकुञ्जरैः पूज्यमानम् ७४१ । ६३ कतरकतमौ जातिपरिप्रश्ने ७४२ । ६४ किं क्षेपे ७४३ ।६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः ७४४ । ६६ प्रशंसावचनैश्च ७४७ । ६७ युवा खलतिपलितवलिनजरतीभिः ७४८ । ६८ कृत्यतुल्याख्या अजात्या ७४९ । ६९ वर्णो वर्णेन ७५० । ७० कुमारः श्रमणादिभिः ७५२ ।७१ चतुष्पादो गर्भिण्या ७५३ ।७२ मयूरव्यंसकादयश्च ७५४ ॥ समर्थोऽन्यपदार्थे च सिद्धशुष्कसन्महद्द्वादश ॥

द्वितीयः पादः ।

१ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ७१२ । २ अर्धं नपुंसकम् ७१३ । ३ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ७१४ ।४ प्राप्तापन्ने च द्वितीयया ७१५ ।५ कालाः परिमाणिना ७१६ । ६ नञ् ७५६ । ७ ईषदकृता ७५५ ।८ षष्ठी ७०२ ।९ याजकादिभिश्च ७०३ ।१० न निर्धारणे ७०४ । ११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ७०५ ।१२ क्तेन च पूजायाम् ७०६ । १३ अधिकरणवाचिना च ७०७ ।१४ कर्मणि च ७०८ । १५ तृजकाभ्यां कर्तरि ७०९ । १६ कर्तरि च ७१० । १७ नित्यं क्रीडाजीविकयोः ७११ ।१८ कुगतिप्रादयः ७६१ । १९ उपपदमतिङ् ७८२ । २० अमैवाव्ययेन ७८३ ॥ १ ॥ २१ तृतीयाप्रभृतीन्यन्यतरस्याम् ७८४ । २२ क्त्वा च ७८५ । २३ शेषो बहुव्रीहिः ८२९ । २४ अनेकमन्यपदार्थे ८३० । २५ संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये ८४३ ।२६ दिङ्नामान्यन्तराले ८४५ ।२७ तत्र तेनेदमिति सरूपे ८४६ । २८ तेन सहेति तुल्ययोगे ८४८ । २९ चार्थे द्वन्द्वः ९०१ । ३० उपसर्जनं पूर्वम् ६५४ । ३१ राजदन्तादिषु परम् ९०२ । ३२ द्वन्द्वे घि ९०३ । ३३ अजाद्यदन्तम् ९०४ । ३४ अल्पाच्तरम् ९०५ । ३५ सप्तमीविशेषणे बहुव्रीहौ ८९८ । ३६ निष्ठा ८९९ । ३७ वाहिताग्न्यादिषु ९०० । ३८ कडाराः कर्मधारये ७६२ ॥ पूर्वापराधरोत्तरं तृतीयाप्रभृतीन्यष्टादश ॥

तृतीयः पादः ।

१ अनभिहिते ५३६ । २ कर्मणि द्वितीया ५३७ । ३ तृतीया च होश्छन्दसि ३३९४ । ४ अन्तरान्तरेणयुक्ते ५४५ । ५ कालाध्वनोरत्यन्तसंयोगे ५५८ । ६ अपवर्गे तृतीया ५६३ । ७ सप्तमीपञ्चम्यौ कारकमध्ये ६४३ ।८ कर्मप्रवचनीययुक्ते द्वितीया ५४८ ।९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ६४५ ।१० पञ्चम्यपाङ्परिभिः ५९८ ।११ प्रतिनिधिप्रतिदाने च यस्मात् ६०० ।१२ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ५८५ । १३ चतुर्थी संप्रदाने ५७० ।१४ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ५८१ ।१५ तुमर्थाच्च भाववचनात् ५८२।

१६ नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ५८३ ।१७ मन्यकर्मण्यनादरे विभाषाप्राणिषु ५८४ ।
१८ कर्तृकरणयोस्तृतीया ५६१ ।१९ सहयुक्तेऽप्रधाने ५६४ । २० येनाङ्गविकारः ५६५
॥ १ ॥ २१ इत्थंभूतलक्षणे ५६६ । २२ संज्ञोऽन्यतरस्यां कर्मणि ५६७ । २३ हेतौ ५६८ ।
२४ अकर्तर्यृणे पञ्चमी ६०१ । २५ विभाषा गुणेऽस्त्रियाम् ६०२ । २६ षष्ठी हेतुप्रयोगे ६०७ ।
२७ सर्वनाम्नस्तृतीया च ६०८ । २८ अपादाने पञ्चमी ५८७ । २९ अन्यारादितरर्तेदिक्-
शब्दाञ्चूत्तरपदाजाहियुक्ते ५९९ । ३० षष्ठ्यतसर्थप्रत्ययेन ६०९ । ३१ एनपा द्वितीया ६१० ।
३२ पृथग्विनानानाभिस्तृतीयान्यतरस्याम् ६०३ । ३३ करणे च स्तोकाल्पकृच्छ्रकतिपय-
स्यासत्त्ववचनस्य ६०४ । ३४ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ६११ । ३५ दूरान्तिकार्थेभ्यो
द्वितीया च ६०५ । ३६ सप्तम्यधिकरणे च ६३३ । ३७ यस्य च भावेन भावलक्षणम् ६३४ ।
३८ षष्ठी चानादरे ६३५ । ३९ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ६३६ । ४०
आयुक्तकुशलाभ्यां चासेवायाम् ६३७ ॥ २ ॥ ४१ यतश्च निर्धारणम् ६३८ । ४२ पञ्चमी
विभक्ते ६३९ । ४३ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ६४० । ४४ प्रसितोत्सुकाभ्यां तृतीया
च ६४१ । ४५ नक्षत्रे च लुपि ६४२ । ४६ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा
५३२ । ४७ संबोधने च ५३३ । ४८ सामन्त्रितम् ४११ । ४९ एकवचनं संबुद्धिः १९२ ।
५० षष्ठी शेषे ६०६ । ५१ ज्ञोऽविदर्थस्य करणे ६१२ । ५२ अधीगर्थदयेशां कर्मणि
६१३ । ५३ कृञः प्रतियत्ने ६१४ । ५४ रुजार्थानां भाववचनानामज्वरेः ६१५ । ५५
आशिषि नाथः ६१६ । ५६ जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ६१७ । ५७ व्यवहृप-
णोः समर्थयोः ६१८ । ५८ दिवस्तदर्थस्य ६१९ । ५९ विभाषोपसर्गे ६२० । ६० द्वितीया
ब्राह्मणे ३३९५ ॥ ३ ॥ ६१ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ६२१ । ६२ चतुर्थ्यर्थे बहुलं
छन्दसि ३३९६ । ६३ यजेश्च करणे ३३९७ । ६४ कृत्वोर्थप्रयोगे कालेऽधिकरणे ६२२ ।
६५ कर्तृकर्मणोः कृति ६२३ । ६६ उभयप्राप्तौ कर्मणि ६२४ । ६७ क्तस्य च वर्तमाने
६२५ । ६८ अधिकरणवाचिनश्च ६२६ । ६९ न लोकाव्ययनिष्ठाखलर्थतृनाम् ६२७ ।
७० अकेनोर्भविष्यदाधमर्ण्ययोः ६२८ । ७१ कृत्यानां कर्तरि वा ६२९ । ७२ तुल्यार्थैरतु-
लोपमाभ्यां तृतीयान्यतरस्याम् ६३० । ७३ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः
६३१ ॥ अनभिहित इत्थंभूतयतश्च प्रेष्यब्रुवोस्त्रयोदश ॥

चतुर्थः पादः ।

१ द्विगुरेकवचनम् ७३१ । २ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ९०६ । ३ अनुवादे चरणा-
नाम् ९०७ । ४ अध्वर्युक्रतुरनपुंसकम् ९०८ । ५ अध्ययनतोऽविप्रकृष्टाख्यानाम् ९०९ ।
६ जातिरप्राणिनाम् ९१० । ७ विशिष्टलिङ्गो नदीदेशोऽग्रामाः ९११ । ८ क्षुद्रजन्तवः ९१२ ।
९ येषां च विरोधः शाश्वतिकः ९१३ । १० शूद्राणामनिरवसितानाम् ९१४ । ११ गवाश्व-
प्रभृतीनि च ९१५ । १२ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तरा-
णाम् ९१६ । १३ विप्रतिषिद्धं चानधिकरणवाचि ९१७ । १४ न दधिपयआदीनि ९१८ । १५
अधिकरणैतावत्त्वे च ९१९ । १६ विभाषा समीपे ९२० । १७ स नपुंसकम् ८२१ । १८
अव्ययीभावश्च ६५९ । १९ तत्पुरुषोऽनञ्कर्मधारयः ८२२ । २० संज्ञायां कन्थोशीनरेषु

८२३ ॥ १ ॥ २१ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ८२४ । २२ छाया बाहुल्ये ८२५ । २३ सभा राजामनुष्यपूर्वा ८२६ । २४ अशाला च ८२७ । २५ विभाषा सेनासुराच्छायाशालानिशानाम् ८२८ । २६ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ८१२ । २७ पूर्ववदश्ववडवौ ८१३ । २८ हेमन्तशिशिरावहोरात्रे च च्छन्दसि ३३९९ । २९ रात्राह्नाहाः पुंसि ८१४ । ३० अपथं नपुंसकम् ८१५ । ३१ अर्धर्चाः पुंसि च ८१६ । ३२ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ३५० । ३३ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ १९६२ । ३४ द्वितीयाटौस्स्वेनः ३५१ । ३५ आर्धधातुके २४३२ । ३६ अदो जग्धिर्ल्यप्ति किति ३०८० । ३७ लुङ्सनोर्घस्लृ २४२७ । ३८ घञपोश्च ३२३६ । ३९ बहुलं छन्दसि ३३९८ । ४० लिट्यन्यतरस्याम् २४२४ ॥ २ ॥ ४१ वेञो वयिः २४११ । ४२ हनो वध लिङि २४३३ । ४३ लुङि च २४३४ । ४४ आत्मनेपदेष्वन्यतरस्याम् २६९६ । ४५ इणो गा लुङि २४५८ । ४६ णौ गमिरबोधने २६०७ । ४७ सनि च २६१५ । ४८ इङश्च २६१६ । ४९ गाङ्लिटि २४५९ । ५० विभाषा लुङ्लृङोः २४६० । ५१ णौ च संश्चङोः २५७९ । ५२ अस्तेर्भूः २४७० । ५३ ब्रुवो वचिः २४५३ । ५४ चक्षिङः ख्याञ् २४३६ । ५५ वा लिटि २४३७ । ५६ अजेर्व्यघञपोः २३९१ । ५७ वा यौ ३२९२ । ५८ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः १२७६ । ५९ पैलादिभ्यश्च १०८४ । ६० इञः प्राचाम् १०८५ ॥ ३ ॥ ६१ न तौल्वलिभ्यः १०८६ । ६२ तद्राजस्य बहुषु तेनैवास्त्रियाम् ११९३ । ६३ यस्कादिभ्यो गोत्रे ११४६ । ६४ यञञोश्च ११०८ । ६५ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ११४७ । ६६ बह्वच इञः प्राच्यभरतेषु ११४८ । ६७ न गोपवनादिभ्यः ११४९ । ६८ तिककितवादिभ्यो द्वन्द्वे ११५० । ६९ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ११५१ । ७० आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ११५२ । ७१ सुपो धातुप्रातिपदिकयोः ६५० । ७२ अदिप्रभृतिभ्यः शपः २४२३ । ७३ बहुलं छन्दसि ३४०० । ७४ यङोऽचि च २६५० । ७५ जुहोत्यादिभ्यः श्लुः २४८९ । ७६ बहुलं छन्दसि ३४०१ । ७७ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु २२२३ । ७८ विभाषा घ्राधेट्शाच्छासः २३७६ । ७९ तनादिभ्यस्तथासोः २५४७ । ८० मन्त्रे घसह्वरणशवृहदहाद्वृच्कृगमिजनिभ्यो लेः ३४०२ ॥ ४ ॥ ८१ आमः २२३८ । ८२ अव्ययादाप्सुपः ४५२ । ८३ नाव्ययीभावादतोऽम्त्वपञ्चम्याः ६५७ । ८४ तृतीयासप्तम्योर्बहुलम् ६५८ । ८५ लुटः प्रथमस्य डारौरसः २१८८ ॥ द्विगुरुपज्ञोपक्रमं वेञो वयिर्न तौल्वलिभ्य आमः पञ्च ॥

इति द्वितीयोऽध्यायः ।

तृतीयोऽध्यायः ।

प्रथमः पादः ।

१ प्रत्ययः १८० । २ परश्च १८१ । ३ आद्युदात्तश्च ३७०८ । ४ अनुदात्तौ सुप्पितौ ३७०९ । ५ गुप्तिज्किद्भ्यः सन् २३९३ । ६ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य २३९४ । ७ धातोः कर्मणः समानकर्तृकादिच्छायां वा २६०८ । ८ सुप आत्मनः क्यच् २६५७ । ९ काम्यच्च २६६३ । १० उपमानादाचारे २६६४ । ११ कर्तुः क्यङ् सलोपश्च २६६५ । १२ भृशादिभ्यो

भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः २६६७ । १३ लोहितादिडाज्भ्यः क्यष् २६६८ । १४ कष्टाय क्रमणे
२६७० । १५ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः २६७१ । १६ बाष्पोष्मभ्यामुद्वमने २६७२ ।
१७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे २६७३ । १८ सुखादिभ्यः कर्तृवेदनायाम् २६७४ ।
१९ नमोवरिवश्चित्रङः क्यच् २६७५ । २० पुच्छभाण्डचीवराण्णिङ् २६७६ ॥ १ ॥ २१
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् २६७७ । २२ धातोरेकाचो हलादेः क्रि-
यासमभिहारे यङ् २६२९ । २३ नित्यं कौटिल्ये गतौ २६३४ । २४ लुपसदचरजपजभदहद-
शगृभ्यो भावगर्हायाम् २६३५ । २५ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण-
चुरादिभ्यो णिच् २५६३ । २६ हेतुमति च २५७६ । २७ कण्ड्वादिभ्यो यक् २६७८ । २८
गुपूधूपविच्छिपणिपनिभ्य आयः २३०३ । २९ ऋतेरीयङ् २४२२ । ३० कमेर्णिङ् २३१० ।
३१ आयादय आर्धधातुके वा २३०५ । ३२ सनाद्यन्ता धातवः २३०४ । ३३ स्यतासी लृलुटोः
२१८६ । ३४ सिब्बहुलं लेटि ३४२५ । ३५ कास्प्रत्ययादाममन्त्रे लिटि २३०६ । ३६ इजा-
देश्च गुरुमतोऽनृच्छः २२३७ । ३७ दयायासश्च २३२४ । ३८ उषविदजागृभ्योऽन्यतरस्याम्
२३४१ । ३९ भीह्रीभृहुवां श्लुवच्च २४९१ । ४० कृञ्चानुप्रयुज्यते लिटि २२३९ ॥ २ ॥ ४१
विदांकुर्वन्त्वित्यन्यतरस्याम् २४६५ । ४२ अभ्युत्सादयांप्रजनयांचिकयांरमयामकः पावयांक्रिया-
द्विदामक्रन्निति च्छन्दसि ३४०३ । ४३ च्लि लुङि २२२१ । ४४ च्लेः सिच् २२२२ । ४५
शल इगुपधादनिटः क्सः २३३६ । ४६ श्लिष आलिङ्गने २५१४ । ४७ न दृशः २४०७ । ४८
णिश्रिद्रुस्रुभ्यः कर्तरि चङ् २३१२ । ४९ विभाषा धेट्श्व्योः २३७५ । ५० गुपेश्छन्दसि
३४०४ । ५१ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ३४०५ । ५२ अस्यतिवक्तिख्यातिभ्योऽङ्
२४३८ । ५३ लिपिसिचिह्वश्च २४१८ । ५४ आत्मनेपदेष्वन्यतरस्याम् २४१९ । ५५
पुषादिद्युताद्य्लृदितः परस्मैपदेषु २३४३ । ५६ सर्तिशास्त्यर्तिभ्यश्च २३८२ । ५७ इरितो
वा २२६९ । ५८ जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च २२९१ । ५९ कृमृदृरुहिभ्यश्छ-
न्दसि ३४०६ । ६० चिण् ते पदः २५१३ ॥ ३ ॥ ६१ दीपजनबुधपूरितायिप्यायिभ्योऽन्य-
तरस्याम् २३२८ । ६२ अचः कर्मकर्तरि २७६८ । ६३ दुहश्च २७६९ । ६४ न रुध
२७७० । ६५ तपोऽनुतापे च २७६० । ६६ चिण्भावकर्मणोः २७५८ । ६७ सार्वधातुके
यक् २७५६ । ६८ कर्तरि शप् २१६७ । ६९ दिवादिभ्यः श्यन् २५०५ । ७० वा भ्रा-
शभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः २३२१ । यसोऽनुपसर्गात् २५२१ । ७२ संयसश्च
२५२२ । ७३ स्वादिभ्यः श्नुः २५२३ । ७४ श्रुवः शृ च २३८६ । ७५ अक्षोऽन्यतरस्याम्
२३३८ । ७६ तनूकरणे तक्षः २३३९ । ७७ तुदादिभ्यः शः २५३४ । ७८ रुधादिभ्यः
श्नम् २५४३ । ७९ तनादिकृञ्भ्य उः २४६६ । ८० धिन्विकृण्व्योर च २३३२ ॥ ४ ॥ ८१
क्र्यादिभ्यः श्ना २५५४ । ८२ स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च २५५५ । ८३ हलः
श्नः शानज्झौ २५५७ । ८४ छन्दसि शायजपि ३४३२ । ८५ व्यत्ययो बहुलम् ३४३३ । ८६
लिङ्याशिष्यङ् ३४३४ । ८७ कर्मवत्कर्मणा तुल्यक्रियः २७६६ । ८८ तपस्तपःकर्मकस्यैव
२७७१ । ८९ न दुहस्नुनमां यक्चिणौ २७६७ । ९० कुषिरजोः प्राचां श्यन्परस्मैपदं च
२७७२ । ९१ धातोः २८२९ । ९२ तत्रोपपदं सप्तमीस्थम् ७८१ । ९३ कृदतिङ् ३७४ । ९४
वासरूपोऽस्त्रियाम् २८३० । ९५ कृत्याः प्राङ्ण्वुलः २८३१ । ९६ तव्यत्तव्यानीयरः २८३४ ।

९७ अचो यत् २८४२ । ९८ पोरदुपधात् २८४४ । ९९ शकिसहोश्च २८४७ । १०० गद-
मदचरयमश्चानुपसर्गे २८४८ ॥ ५ ॥ १०१ अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु २८४९ ।
१०२ वह्यं करणम् २८५० । १०३ अर्यः स्वामिवैश्ययोः २८५१ । १०४ उपसर्या काल्या
प्रजने २८५२ । १०५ अजर्यं संगतम् २८५३ । १०६ वदः सुपि क्यप्च २८५४ । १०७ भुवो
भावे २८५५ । १०८ हनस्त च २८५६ । १०९ एतिस्तुशास्वृदृजुषः क्यप् २८५७ । ११०
ऋदुपधाच्चाक्लृपिचृतेः २८५९ । १११ ई च खनः २८६० । ११२ भृञोऽसंज्ञायाम् २८६१ ।
११३ मृजेर्विभाषा २८६२ । ११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः २८६५ ।
११५ भिद्योद्ध्यौ नदे २८६६ । ११६ पुष्यसिध्यौ नक्षत्रे २८६७ । ११७ विपूयविनीयजित्या
मुञ्जकल्कहलिषु २८६८ । ११८ प्रत्यपिभ्यां ग्रहेश्छन्दसि २८६९ । ११९ पदास्वैरिबाह्यापक्ष्येषु
च २८७० । १२० विभाषा कृवृषोः २८७१ ॥ ६ ॥ १२१ युग्यं च पत्रे २८७३ । १२२
अमावस्यदन्यतरस्याम् २८७४ । १२३ छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्या-
ध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ३४०७ । १२४
ऋहलोर्ण्यत् २८७२ । १२५ ओरावश्यके २८८६ । १२६ आसुयुवपिरपिलपित्रपिचमश्च २८८७ ।
१२७ आनाय्योऽनित्ये २८८८ । १२८ प्रणाय्योऽसंमतौ २८८९ । १२९ पाय्यसांनाय्यनिकाय्य-
धाय्या मानहविर्निवाससामिधेनीषु २८९० । १३० क्रतौ कुण्डपाय्यसंचाय्यौ २८९१ । १३१
अग्नौ परिचाय्योपचाय्यसमूह्याः २८९२ । १३२ चित्याग्निचित्ये च २८९३ । १३३ ण्वुल्तृचौ २८९५ ।
१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः २८९६ । १३५ इगुपधज्ञाप्रीकिरः कः २८९७ ।
१३६ आतश्चोपसर्गे २८९८ । १३७ पाघ्राध्माधेट्दृशः शः २८९९ । १३८ अनुपसर्गाल्लिम्पवि-
न्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च २९०० । १३९ ददातिदधात्योर्विभाषा २९०१ । १४०
ज्वलितिकसन्तेभ्यो णः २९०२ ॥ ७ ॥ १४१ श्याद्व्यधास्रुसंस्रुतीणवसावहृलिहश्लिषश्वसश्च
२९०३ । १४२ दुन्योरनुपसर्गे २९०४ । १४३ विभाषा ग्रहः २९०५ । १४४ गेहे कः २९०६ ।
१४५ । शिल्पिनि ष्वुन् २९०७ । १४६ गस्थकन् २९०८ । १४७ ण्युट् च २९०९ । १४८ हश्च
व्रीहिकालयोः २९१० । १४९ प्रुसृल्वः समभिहारे वुन् २९११ । १५० आशिषि च २९१२ ॥
प्रत्ययो मुण्डविदांदीपजनत्र्यादिभ्योऽवद्ययुग्यं च श्याद्व्यधा दश ॥

द्वितीयः पादः ।

१ कर्मण्यण् २९१३ । २ ह्वावामश्च २९१४ । ३ आतोऽनुपसर्गे कः २९१५ । ४ सुपि स्थः
२९१६ । ५ तुन्दशोकयोः परिमृजापनुदोः २९१९ । ६ प्रे दाज्ञः २९२० । ७ समि ख्यः
२९२१ । ८ गापोष्टक् २९२२ । ९ हरतेरनुद्यमनेऽच् २९२३ । १० वयसि च २९२४ । ११
आङि ताच्छील्ये २९२५ । १२ अर्हः २९२६ । १३ स्तबकर्णयो रमिजपोः २९२७ । १४
शमि धातोः संज्ञायाम् २९२८ । १५ अधिकरणे शेतेः २९२९ । १६ चरेष्टः २९३० । १७
भिक्षासेनादायेषु च २९३१ । १८ पुरोऽग्रतोऽग्रेषु सर्तेः २९३२ । १९ पूर्वे कर्तरि २९३३ ।
२० कृञो हेतुताच्छील्यानुलोम्येषु २९३४ ॥ १ ॥ २१ दिवाविभानिशाप्रभाभास्कारान्तानन्ता-
दिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु २९३५ । २२
कर्मणि भृतौ २९३६ । २३ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु २९३७ । २४ स्तम्ब-
शकृतोरिन् २९३८ । २५ हरतेर्दृतिनाथयोः पशौ २९३९ । २६ फलेग्रहिरात्मंभरिश्च २९४०-

२७ छन्दसि वनसनरक्षिमथाम् ३४०८ । २८ एजेः खश् २९४१ । २९ नासिकास्तनयो-
र्ध्माधेटोः २९४४ । ३० नाडीमुष्टयोश्च २९४५ । ३१ उदि कूले रुजिवहोः २९४६ । ३२
वहाभ्रे लिहः २९४७ । ३३ परिमाणे पचः २९४८ । ३४ मितनखे च २९४९ । ३५ विध्वरुषोस्तुदः
२९५० । ३६ असूर्यललाटयोर्दृशितपोः २९५१ । ३७ उग्रंपश्येरंमदपाणिंधमाश्च २९५२ ।
३८ प्रियवशे वदः खच् २९५३ । ३९ द्विषत्परयोस्तापेः २९५४ । ४० वाचि यमो व्रते २९५६ ।
॥ २ ॥ ४१ पूःसर्वयोर्दारिसहोः २९५८ । ४२ सर्वकूलाभ्रकरीषेषु कषः २९५९ । ४३ मेघर्ति-
भयेषु कृञः २९६० । ४४ क्षेमप्रियमद्रेऽण्च २९६१ । ४५ आशिते भुवः करणभावयोः २९६२ -
४६ संज्ञायां भृतॄवृजिधारिसहितपिदमः २९६३ । ४७ गमश्च २९६४ । ४८ अन्तात्यन्ताध्व-
दूरपारसर्वानन्तेषु डः २९६५ । ४९ आशिषि हनः २९६६ । ५० अपे क्लेशतमसोः २९६७ । ५१
कुमारशीर्षयोर्णिनिः २९६८ । ५२ लक्षणे जायापत्योष्टक् २९६९ । ५३ अमनुष्यकर्तृके च
२९७० । ५४ शक्तौ हस्तिकपाटयोः २९७१ । ५५ पाणिघताडघौ शिल्पिनि २९७२ । ५६
आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् २९७३ । ५७ कर्तरि
भुवः खिष्णुच्खुकञौ २९७४ । ५८ स्पृशोऽनुदके क्विन् ४३२ । ५९ ऋत्विग्दधृक्स्रग्दिगुष्णिग-
ञ्चुयुजिक्रुञ्चां च ३७३ । ६० त्यदादिषु दृशोऽनालोचने कञ्च ४२९ ॥ ३ ॥ ६१ सत्सूद्विष-
द्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् २९७५ । ६२ भजो ण्विः २९७६ । ६३
छन्दसि सहः ३४०९ । ६४ वहश्च ३४१० । ६५ कव्यपुरीषपुरीष्येषु ञ्युट् ३४११ । ६६
हव्येऽनन्तःपादम् ३४१२ । ६७ जनसनखनक्रमगमो विट् ३४१३ । ६८ अदोऽनन्ने २९७७ ।
६९ क्रव्ये च २९७८ । ७० दुहः कब्घश्च २९७९ । ७१ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्
३४१४ । ७२ अवे यजः ३४१५ । ७३ विजुपे छन्दसि ३४१७ । ७४ आतो मनिन्क्वनिब्वनि-
पश्च ३४१८ । ७५ अन्येभ्योऽपि दृश्यन्ते २९८० । ७६ क्विप् च २९८३ । ७७ स्थः क च
२९८७ । ७८ सुप्यजातौ णिनिस्ताच्छील्ये २९८८ । ७९ कर्तर्युपमाने २९८९ । ८० व्रते
२९९० ॥ ४ ॥ ८१ बहुलमाभीक्ष्ण्ये २९९१ । ८२ मनः २९९२ । ८३ आत्ममाने खश्च २९९३ ।
८४ भूते २९९५ । ८५ करणे यजः २९९६ । ८६ कर्मणि हनः २९९७ । ८७ ब्रह्मभ्रूणवृत्रेषु
क्विप् २९९८ । ८८ बहुलं छन्दसि ३४१९ । ८९ सुकर्मपापमन्त्रपुण्येषु कृञः २९९९ । ९०
सोमे सुञः ३००० । ९१ अग्नौ चेः ३००१ । ९२ कर्मण्यग्न्याख्यायाम् ३००२ । ९३ कर्म-
णीनिविक्रियः ३००३ । ९४ दृशेः क्वनिप् ३००४ । ९५ राजनि युधिकृञः ३००५ । ९६ सहे
च ३००६ । ९७ सप्तम्यां जनेर्डः ३००७ । ९८ पञ्चम्यामजातौ ३००८ । ९९ उपसर्गे च
संज्ञायाम् ३००९ । १०० अनौ कर्मणि ३०१० ॥ ५ ॥ १०१ अन्येष्वपि दृश्यते ३०११ ।
१०२ निष्ठा ३०१३ । १०३ सुयजोर्ङ्वनिप् ३०९१ । १०४ जीर्यतेरतृन् ३०९२ । १०५ छन्दसि
लिट् ३०९३ । १०६ लिटः कानज्वा ३०९४ । १०७ क्वसुश्च ३०९५ । १०८ भाषायां सदव-
सश्रुवः ३०९७ । १०९ उपेयिवाननाश्वाननूचानश्च ३०९८ । ११० लुङ् २२१८ । १११ अन-
द्यतने लङ् २२०५ । ११२ अभिज्ञावचने लृट् २७७३ । ११३ न यदि २७७४ । ११४ वि-
भाषा साकाङ्क्षे २७७५ । ११५ परोक्षे लिट् २१७१ । ११६ हशश्वतोर्लङ् च २७७६ । ११७ प्रश्ने
चासन्नकाले २७७७ । ११८ लट् स्मे २७७८ । ११९ अपरोक्षे च २७७९ । १२० ननौ पृष्ट-
प्रतिवचने २७८० ॥ ६ ॥ १२१ नन्वोर्विभाषा २७८१ । १२२ पुरि लुङ्चास्मे २७८२ । १२३

वर्तमाने लट् २१५१ । १२४ लटः शतृशानचावप्रथमासमानाधिकरणे ३१०० । १२५ संबोधने च ३१०२ । १२६ लक्षणहेत्वोः क्रियायाः ३१०३ । १२७ तौ सत् ३१०६ । १२८ पूङ्यजोः शानन् ३१०८ । १२९ ताच्छील्यवयोवचनशक्तिषु चानश् ३१०९ । १३० इङ्धार्योः शत्रकृच्छ्रिणि ३११० । १३१ द्विषोऽमित्रे ३१११ । १३२ सुञो यज्ञसंयोगे ३११२ । १३३ अर्हः प्रशंसायाम् ३११३ । १३४ आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु ३११४ । १३५ तृन् ३११५ । १३६ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ३११६ । १३७ णेश्छन्दसि ३११७ । १३८ भुवश्च ३११८ । १३९ ग्लाजिस्थश्च ग्स्नुः ३११९ । १४० त्रसिगृधिधृषिक्षिपेः क्नुः ३१२० ॥ ७ ॥ १४१ शमित्यष्टाभ्यो घिनुण् ३१२१ । १४२ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ३१२२ । १४३ वौ कषलसकत्थस्रम्भः ३१२३ । १४४ अपे च लषः ३१२४ । १४५ प्रे लपसृद्रुमथवदवसः ३१२५ । १४६ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् ३१२६ । १४७ देविक्रुशोश्चोपसर्गे ३१२७ । १४८ चलनशब्दार्थादकर्मकाद्युच् ३१२८ । १४९ अनुदात्तेतश्च हलादेः ३१२९ । १५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ३१३० । १५१ क्रुधमण्डार्थेभ्यश्च ३१३१ । १५२ न यः ३१३२ । १५३ सूददीपदीक्षश्च ३१३३ । १५४ लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ् ३१३४ । १५५ जल्पभिक्षकुट्टलुण्टवृङः षाकन् ३१३५ । १५६ प्रजोरिनिः ३१३६ । १५७ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ३१३७ । १५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ३१३८ । १५९ दाधेट्सिशदसदो रुः ३१३९ । १६० सृघस्यदः क्मरच् ३१४० ॥ ८ ॥ १६१ भञ्जभासमिदो घुरच् ३१४१ । १६२ विदिभिदिच्छिदेः कुरच् ३१४२ । १६३ इण्नशजिसर्तिभ्यः क्वरप् ३१४३ । १६४ गत्वरश्च ३१४४ । १६५ जागरूकः ३१४५ । १६६ यजजपदशां यङः ३१४६ । १६७ नमिकम्पिस्म्यजसकमहिंसदीपो रः ३१४७ । १६८ सनाशंसभिक्ष उः ३१४८ । १६९ विन्दुरिच्छुः ३१४९ । १७० क्याच्छन्दसि ३१५० । १७१ आदृगमहनजनः किकिनौ लिट् च ३१५१ । १७२ स्वपितृषोर्नजिङ् ३१५२ । १७३ शॄवन्द्योरारुः ३१५३ । १७४ भियः क्रुक्लुकनौ ३१५४ । १७५ स्थेशभासपिसकसो वरच् ३१५५ । १७६ यश्च यङः ३१५६ । १७७ भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ३१५७ । १७८ अन्येभ्योऽपि दृश्यते ३१५८ । १७९ भुवः संज्ञान्तरयोः ३१५९ । १८० विप्रसंभ्यो ड्वसंज्ञायाम् ३१६० ॥ ९ ॥ १८१ धः कर्मणि ष्ट्रन् ३१६१ । १८२ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ३१६२ । १८३ हलसूकरयोः पुवः ३१६४ । १८४ अर्तिलूधूसूखनसहचर इत्रः ३१६५ । १८५ पुवः संज्ञायाम् ३१६६ । १८६ कर्तरि चर्षिदेवतयोः ३१६७ । १८७ ञीतः क्तः ३०८८ । १८८ मतिबुद्धिपूजार्थेभ्यश्च ३०८९ ॥ कर्मणि दिवापूःसर्वसत्सूबहुलमन्येष्वपि नन्वोः शामिति भञ्जभासधः कर्मण्यष्टौ ॥

तृतीयः पादः ।

१ उणादयो बहुलम् ३१६९ । २ भूतेऽपि दृश्यन्ते ३१७० । ३ भविष्यति गम्यादयः ३१७१ । ४ यावत्पुरानिपातयोर्लट् २७८३ । ५ विभाषा कदाकर्ह्योः २७८४ । ६ किंवृत्ते लिप्सायाम् २७८५ । ७ लिप्स्यमानसिद्धौ च २७८६ । ८ लोडर्थलक्षणे च २७८७ । ९ लिङ्

तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३१७९ । ११ भाववचनाश्च
चोऽर्धमौहूर्तिके २७८८ । १० तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३१७९ । ११ भाववचनाश्च
३१८० । १२ अण्कर्मणि च ३१८१ । १३ लृट् शेषे च २१९३ । १४ लृटः सद्वा ३१०७ । १५
अनद्यतने लुट् २१८९ । १६ पदरुजविशस्पृशो घञ् ३१८२ । १७ सृ स्थिरे ३१८३ । १८
भावे ३१८४ । १९ अकर्तरि च कारके संज्ञायाम् ३१८८ । २० परिमाणाख्यायां सर्वेभ्यः
३१९० ॥ १ ॥ २१ इङश्च ३१९१ । २२ उपसर्गे रुवः ३१९२ । २३ समि युद्रुदुवः ३१९४ ।
२४ श्रिणीभुवोऽनुपसर्गे ३१९५ । २५ वौ क्षुश्रुवः ३१९६ । २६ अवोदोर्नियः ३१९७ । २७
प्रे द्रुस्तुस्रुवः ३१९८ । २८ निरभ्योः पूल्वोः ३१९९ । २९ उन्न्योर्ग्रः ३२०० । ३० कॄ धान्ये
३२०१ । ३१ यज्ञे समि स्तुवः ३२०२ । ३२ प्रे स्त्रोऽयज्ञे ३२०३ । ३३ प्रथने वावशब्दे
३२०४ । ३४ छन्दोनाम्नि च ३२०५ । ३५ उदि ग्रहः ३२०७ । ३६ समि मुष्टौ ३२०८ ।
३७ परिन्योर्नीणोर्द्यूताभ्रेषयोः ३२०९ । ३८ परावनुपात्यय इणः ३२१० । ३९ व्युपयोः शेतेः
पर्याये ३२११ । ४० हस्तादाने चेरस्तेये ३२१२ ॥ २ ॥ ४१ निवासचितिशरीरोपसमाधाने-
ष्वादेश्च कः ३२१३ । ४२ संघे चानौत्तराधर्ये ३२१४ । ४३ कर्मव्यतिहारे णच्स्त्रियाम् ३२१५ ।
४४ अभिविधौ भाव इनुण् ३२१८ । ४५ आक्रोशेऽवन्योर्ग्रहः ३२२० । ४६ प्रे लिप्सायाम्
३२२१ । ४७ परौ यज्ञे ३२२२ । ४८ नौ वृ धान्ये ३२२३ । ४९ उदि श्रयतियौतिपूद्रुवः
३२२४ । ५० विभाषाङि रुप्लुवोः ३२२५ । ५१ अवे ग्रहो वर्षप्रतिबन्धे ३२२६ ।
५२ प्रे वणिजाम् ३२२७ । ५३ रश्मौ च ३२२८ । ५४ वृणोतेराच्छादने ३२२९ ।
५५ परौ भुवोऽवज्ञाने ३२३० । ५६ एरच् ३२३१ । ५७ ऋदोरप् ३२३२ ।
५८ ग्रहवृदृनिश्चिगमश्च ३२३४ । ५९ उपसर्गेऽदः ३२३५ । ६० नौ ण च ३२३७ ॥ ३ ॥
६१ व्यधजपोरनुपसर्गे ३२३८ । ६२ स्वनहसोर्वा ३२३९ । ६३ यमः समुपनिविषु च ३२४० ।
६४ नौ गदनदपठस्वनः ३२४१ । ६५ क्वणो वीणायां च ३२४२ । ६६ नित्यं पणः परिमाणे
३२४३ । ६७ मदोऽनुपसर्गे ३२४४ । ६८ प्रमदसंमदौ हर्षे ३२४५ । ६९ समुदोरजः पशुषु
३२४६ । ७० अक्षेषु ग्लहः ३२४७ । ७१ प्रजने सर्तेः ३२४८ । ७२ ह्वः संप्रसारणं च
न्यभ्युपविषु ३२४९ । ७३ आङि युद्धे ३२५० । ७४ निपानमाहावः ३२५१ । ७५ भावेऽनुप-
सर्गस्य ३२५२ । ७६ हनश्च वधः ३२५३ । ७७ मूर्तौ घनः ३२५४ । ७८ अन्तर्घनो
देशे ३२५५ । ७९ अगारैकदेशे प्रघणः प्रघाणश्च ३२५६ । ८० उद्घनोऽत्याधानम्
३२५७ ॥ ४ ॥ ८१ अपघनोऽङ्गम् ३२५८ । ८२ करणेऽयोविद्रुषु ३२५९ । ८३ स्तम्बे
क च ३२६० । ८४ परौ घः ३२६१ । ८५ उपघ्न आश्रये ३२६३ । ८६ संघोद्घौ गणप्रशंसयोः
३२६४ । ८७ निघो निमितम् ३२६५ । ८८ ड्वितः क्त्रिः ३२६६ । ८९ ट्वितोऽथुच्
३२६७ । ९० यजयाचयतविच्छप्रच्छरक्षो नङ् ३२६८ । ९१ स्वपो नन् ३२६९ । ९२
उपसर्गे घोः किः ३२७० । ९३ कर्मण्यधिकरणे च ३२७१ । ९४ स्त्रियां क्तिन् ३२७२ । ९५
स्थागापापचो भावे ३२७३ । ९६ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ३४२० । ९७
ऊतियूतिजूतिसातिहेतिकीर्तयश्च ३२७४ । ९८ व्रजयजोर्भावे क्यप् ३२७५ । ९९ संज्ञायां
समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ३२७६ । १०० कृञः श च ३२७७ ॥ ५ ॥ १०१
इच्छा ३२७८ । १०२ अ प्रत्ययात् ३२७९ । १०३ गुरोश्च हलः ३२८० । १०४ षिद्भिदा-
दिभ्योऽङ् ३२८१ । १०५ चिन्तिपूजिकथिकुम्बिचर्चश्च ३२८२ । १०६ आतश्चोपसर्गे

३२८३ । १०७ ण्यासश्रन्थो युच् ३२८४ । १०८ रोगाख्यायां ण्वुल्बहुलम् ३२८५ । १०९ संज्ञायाम् ३२८६ । ११० विभाषाख्यानपरिप्रश्नयोरिञ्च ३२८७ । १११ पर्यायार्हर्णोत्पत्तिषु ण्वुच् ३२८८ । ११२ आक्रोशे नञ्यनिः ३२८९ । ११३ कृत्यल्युटो बहुलम् २८४१ । ११४ नपुंसके भावे क्तः ३०९० । ११५ ल्युट् च ३२९० । ११६ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ३२९१ । ११७ करणाधिकरणयोश्च ३२९३ । ११८ पुंसि संज्ञायां घः प्रायेण ३२९६ । ११९ गोचरसंचरवहव्रजव्यजापणनिगमाश्च ३२९८ । १२० अवे तॄस्त्रोर्घञ् ३२९९ ॥ ६ ॥ १२१ हलश्च ३३०० । १२२ अध्यायन्यायोद्यावसंहाराधारावायाश्च ३३०१ । १२३ उदङ्कोऽनुदके ३३०२ । १२४ जालमानायः ३३०३ । १२५ खनो घ च ३३०४ । १२६ ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ३३०५ । १२७ कर्तृकर्मणोश्च भूकृञोः ३३०८ । १२८ आतो युच् ३३०९ । १२९ छन्दसि गत्यर्थेभ्यः ३४२१ । १३० अन्येभ्योऽपि दृश्यते ३४२२ । १३१ वर्तमानसामीप्ये वर्तमानवद्वा २७८९ । १३२ आशंसायां भूतवच्च २७९० । १३३ क्षिप्रवचने लृट् २७९१ । १३४ आशंसावचने लिङ् २७९२ । १३५ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः २७९३ । १३६ भविष्यति मर्यादावचनेऽवरस्मिन् २७९४ । १३७ कालविभागे चानहोरात्राणाम् २७९५ । १३८ परस्मिन्विभाषा २७९६ । १३९ लिङ्निमित्ते लृङ् क्रियातिपत्तौ २२२९ । १४० भूते च २७९७ ॥ ७ ॥ १४१ वोताप्योः २७९८ । १४२ गर्हायां लडपिजात्वोः २७९९ । १४३ विभाषा कथमि लिङ् च २८०० । १४४ किंवृत्ते लिङ्लृटौ २८०१ । १४५ अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि २८०२ । १४६ किंकिलास्त्यर्थेषु लृट् २८०३ । १४७ जातुयदोर्लिङ् २८०४ । १४८ यच्चयत्रयोः २८०५ । १४९ गर्हायां च २८०६ । १५० चित्रीकरणे च २८०७ । १५१ शेषे लृडयदौ २८०८ । १५२ उताप्योः समर्थयोर्लिङ् २८०९ । १५३ कामप्रवेदनेऽकच्चिति २८१० । १५४ संभावनेऽलमिति चेत्सिद्धाप्रयोगे २८११ । १५५ विभाषा धातौ संभावनवचनेऽयदि २८१२ । १५६ हेतुहेतुमतोर्लिङ् २८१३ । १५७ इच्छार्थेषु लिङ्लोटौ २८१४ । १५८ समानकर्तृकेषु तुमुन् ३१७६ । १५९ लिङ् च २८१५ । १६० इच्छार्थेभ्यो विभाषा वर्तमाने २८१६ ॥ ८ ॥ १६१ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् २२०८ । १६२ लोट् च २१९४ । १६३ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च २८१७ । १६४ लिङ् चोर्ध्वमौहूर्तिके २८१८ । १६५ स्मे लोट् २८१९ । १६६ अधीष्टे च २८२० । १६७ कालसमयवेलासु तुमुन् ३१७७ । १६८ लिङ्यदि २८२१ । १६९ अर्हे कृत्यतृचश्च २८२२ । १७० आवश्यकाधमर्ण्ययोर्णिनिः ३३११ । १७१ कृत्याश्च ३३१२ । १७२ शकि लिङ् च २८२३ । १७३ आशिषि लिङ्लोटौ २१९५ । १७४ क्तिच्क्तौ च संज्ञायाम् ३३१३ । १७५ माङि लुङ् २२१९ । १७६ स्मोत्तरे लङ् च २२२० ॥ उणादय इङो निवासव्यधजपोरपघन इच्छा हलश्च वोताप्योर्विधिषोडश ॥

चतुर्थः पादः ।

१ धातुसंबन्धे प्रत्ययाः २८२४ । २ क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः २८२५ । ३ समुच्चयेऽन्यतरस्याम् २८२६ । ४ यथाविध्यनुप्रयोगः पूर्वस्मिन् २८२७ । ५ समुच्चये सामान्यवचनस्य २८२८ । ६ छन्दसि लुङ्लङ्लिटः ३४२३ । ७ लिङर्थे लेट् ३४२४ । ८ उपसंवादाशङ्क

योश्च ३४३१ । ९ तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः
३४३६ । १० प्रयै रोहिष्यै अव्यथिष्यै ३४३७ । ११ दृशे विख्ये च ३४३८ । १२ शकि णमुल्कमुलौ
३४३९ । १३ ईश्वरे तोसुन्कसुनौ ३४४० । १४ कृत्यार्थे तवैकेन्केन्यत्वनः ३४४१ । १५ अव-
चक्षे च ३४४२ । १६ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ३४४३ । १७ सृपि-
तृदोः कसुन् ३४४४ । १८ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ३३१६ । १९ उदीचां माङो
व्यतीहारे ३३१७ । २० परावरयोगे च ३३१९ ॥ १ ॥ २१ समानकर्तृकयोः पूर्वकाले
३३२० । २२ आभीक्ष्ण्ये णमुल्च ३३४३ । २३ न यद्यनाकाङ्क्षे ३३४४ । २४ विभाषा-
ग्रेप्रथमपूर्वेषु ३३४५ । २५ कर्मण्याक्रोशे कृञः खमुञ् ३३४६ । २६ स्वादुमि णमुल् ३३४७ । २७
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ३३४८ । २८ यथातथयोरसूयाप्रतिवचने ३३४९ । २९
कर्मणि दृशिविदोः साकल्ये ३३५० । ३० यावति विन्दजीवोः ३३५१ । ३१ चर्मोदरयोः पूरेः
३३५२ । ३२ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ३३५३ । ३३ चेले क्नोपेः ३३५४ । ३४
निमूलसमूलयोः कषः ३३५५ । ३५ शुष्कचूर्णरूक्षेषु पिषः ३३५६ । ३६ समूलाकृतजीवेषु
हन्कृञ्ग्रहः ३३५७ । ३७ करणे हनः ३३५८ । ३८ स्नेहने पिषः ३३५९ । ३९ हस्ते वर्ति-
ग्रहोः ३३६० । ४० स्वे पुषः ३३६१ ॥ २ ॥ ४१ अधिकरणे बन्धः ३३६२ । ४२ संज्ञायाम्
३३६३ । ४३ कर्त्रोर्जीवपुरुषयोर्नशिवहोः ३३६४ । ४४ ऊर्ध्वे शुषिपूरोः ३३६५ । ४५ उप-
माने कर्मणि च ३३६६ । ४६ कषादिषु यथाविध्यनुप्रयोगः ३३६७ । ४७ उपदंशस्तृतीया-
याम् ३३६८ । ४८ हिंसार्थानां च समानकर्मकाणाम् ३३६९ । ४९ सप्तम्यां चोपपीडरुधकर्ष-
३३७० । ५० समासत्तौ ३३७१ । ५१ प्रमाणे च ३३७२ । ५२ अपादाने परीप्सायाम् ३३७३ ।
५३ द्वितीयायां च ३३७४ । ५४ स्वाङ्गेऽध्रुवे ३३७६ । ५५ परिक्लिश्यमाने च ३३७७ । ५६
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ३३७८ । ५७ अस्यतितृषोः क्रियान्तरे कालेषु
३३७९ । ५८ नाम्न्यादिशिग्रहोः ३३८० । ५९ अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ
३३८१ । ६० तिर्यच्यपवर्गे ३३८२ ॥ ३ ॥ ६१ स्वाङ्गे तस्प्रत्यये कृभ्वोः ३३८३ । ६२ ना-
धार्थप्रत्यये च्व्यर्थे ३३८४ । ६३ तूष्णीमि भुवः ३३८५ । ६४ अन्वच्यानुलोम्ये ३३८६ । ६५
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ३१७७ । ६६ पर्याप्तिवचनेष्वलमर्थेषु
३१७८ । ६७ कर्तरि कृत् २८३२ । ६८ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा
२८९४ । ६९ लः कर्मणि च भावे चाकर्मकेभ्यः २१५२ । ७० तयोरेव कृत्यक्तखलर्थाः
२८३३ । ७१ आदिकर्मणि क्तः कर्तरि च ३०५३ । ७२ गत्यर्थाकर्मकश्लिषशीङ्स्थासवसज-
नरुहजीर्यतिभ्यश्च ३०८६ । ७३ दाशगोघ्नौ संप्रदाने ३१७२ । ७४ भीमादयोऽपादाने ३१७३ ।
७५ ताभ्यामन्यत्रोणादयः ३१७४ ७६ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ३०८७ ।
७७ लस्य २१५३ । ७८ तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् २१५४ ।
७९ टित आत्मनेपदानां टेरे २२२३ । ८० थासः से २२३६ ॥ ४ ॥ ८१ लिटस्तझयोरेशि-
रेच् २२४१ । ८२ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः २१७३ । ८३ विदो लटो वा २४६४ ।
८४ ब्रुवः पञ्चानामादित आहो ब्रुवः २४५० । ८५ लोटो लङ्वत् २१९८ । ८६ एरुः २१९६ ।
८७ सेर्ह्यपिच्च २२०१ । ८८ वा छन्दसि ३५५३ । ८९ मेर्निः २२०३ । ९० आमेतः २२५१ ।
९१ सवाभ्यां वामौ २२५२ । ९२ आडुत्तमस्य पिच्च २२०४ । ९३ एत ऐ २२५३ । ९४

लेटोऽडाटौ ३४२७ । ९५ आत ऐ ३४२९ । ९६ वैतोऽन्यत्र ३४३० । ९७ इतश्च लोपः परस्मैपदेषु ३४२६ । ९८ स उत्तमस्य ३४२८ । ९९ नित्यं ङितः २२०० । १०० इतश्च २२०७ ॥ ५ ॥ १०१ तस्थस्थमिपां तान्तन्तामः २१९९ । १०२ लिङः सीयुट् २२५५ । १०३ यासुट्परस्मैपदेषूदात्तो ङिच्च २२०९ । १०४ किदाशिषि २२१६ । १०५ झस्य रन् २२५६ । १०६ इटोऽत् २२५७ । १०७ सुट् तिथोः २२१० । १०८ झेर्जुस् २२१३ । १०९ सिजभ्यस्तविदिभ्यश्च २२२६ । ११० आतः २२२७ । १११ लङः शाकटायनस्यैव २४६३ । ११२ द्विषश्च २४३५ । ११३ तिङ्शित्सार्वधातुकम् २१६६ । ११४ आर्धधातुकं शेषः २१८७ । ११५ लिट् च २१७२ । ११६ लिङाशिषि २२१५ । ११७ छन्दस्युभयथा ३४३९ ॥ धातुसंबन्धे समानाधिकरणे स्वाङ्गे लिटस्तस्थस्थमिपां सप्तदश ॥

इति तृतीयोऽध्यायः ।

चतुर्थोऽध्यायः ।

प्रथमः पादः ।

१ ङ्याप्प्रातिपदिकात् १८२ । २ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् १८३ । ३ स्त्रियाम् ४५३ । ४ अजाद्यतष्टाप् ४५४ । ५ ऋन्नेभ्यो ङीप् ३०६ । ६ उगितश्च ४५५ । ७ वनो र च ४५६ । ८ पादोऽन्यतरस्याम् ४५७ । ९ टाबृचि ४५८ । १० न षट्स्वस्रादिभ्यः ३०८ । ११ मनः ४५९ । १२ अनो बहुव्रीहेः ४६० । १३ डाबुभाभ्यामन्यतरस्याम् ४६१ । १४ अनुपसर्जनात् ४६९ । १५ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ४७० । १६ यञश्च ४७१ । १७ प्राचां ष्फस्तद्धितः ४७३ । १८ सर्वत्र लोहितादिकतन्तेभ्यः ४७६ । १९ कौरव्यमाण्डूकाभ्यां च ४७७ । २० वयसि प्रथमे ४७८ ॥ १ ॥ २१ द्विगोः ४७९ । २२ अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि ४८० । २३ काण्डान्तात्क्षेत्रे ४८१ । २४ पुरुषात्प्रमाणेऽन्यतरस्याम् ४८२ । २५ बहुव्रीहेरूधसो ङीष् ४८४ । २६ संख्याव्ययादेर्ङीप् ४८५ । २७ दामहायनान्ताच्च ४८६ । २८ अन उपधालोपिनोऽन्यतरस्याम् ४६२ । २९ नित्यं संज्ञाछन्दसोः ४८७ । ३० केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ४८८ । ३१ रात्रेश्चाजसौ ३४४५ । ३२ अन्तर्वत्पतिवतोर्नुक् ४८९ । ३३ पत्युर्नो यज्ञसंयोगे ४९० । ३४ विभाषा सपूर्वस्य ४९१ । ३५ नित्यं सपत्न्यादिषु ४९२ । ३६ पूतक्रतोरै च ४९३ । ३७ वृषाकप्यग्निकुसितकुसिदानामुदात्तः ४९४ । ३८ मनोरौ वा ४९५ । ३९ वर्णादनुदात्तात्तोपधात्तो नः ४९६ । ४० अन्यतो ङीष् ४९७ ॥ २ ॥ ४१ षिद्गौरादिभ्यश्च ४९८ । ४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ५०० । ४३ शोणात्प्राचाम् ५०१ । ४४ वोतो गुणवचनात् ५०२ । ४५ बह्वादिभ्यश्च ५०३ । ४६ नित्यं छन्दसि ३४४६ । ४७ भुवश्च ३४४७ । ४८ पुंयोगादाख्यायाम् ५०४ । ४९ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ५०५ । ५० क्रीतात्करणपूर्वात् ५०६ । ५१ क्तादल्पाख्यायाम् ५०७ । ५२ बहुव्रीहेश्चान्तोदात्तात् ५०८ । ५३ अस्वाङ्गपूर्वपदाद्वा ५०९ । ५४ स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ५१० । ५५ नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ५११ । ५६ न क्रोडा-

दिबह्वचः ५१२ । ५७ सहनञ्विद्यमानपूर्वाच्च ५१३ । ५८ नखमुखात्संज्ञायाम् ५१४ । ५९
दीर्घजिह्वी च छन्दसि ३४४८ । ६० दिक्पूर्वपदान्ङीप् ५१५ ॥ ३ ॥ ६१ वाहः ५१६ । ६२
सख्यशिश्वीति भाषायाम् ५१७ । ६३ जातेरस्त्रीविषयादयोपधात् ५१८ । ६४ पाककर्णपर्णपुष्प-
फलमूलवालोत्तरपदाच्च ५१९ । ६५ इतो मनुष्यजातेः ५२० । ६६ ऊङुतः ५२१ । ६७ बाह्व-
न्तात्संज्ञायाम् ५२२ । ६८ पङ्गोश्च ५२३ । ६९ ऊरूत्तरपदादौपम्ये ५२४ । ७० संहितशफल-
क्षणवामादेश्च ५२५ । ७१ कद्रुकमण्डल्वोश्छन्दसि ३४४९ । ७२ संज्ञायाम् ५२६ । ७३ शा-
र्ङ्गरवाद्यञो ङीन् ५२७ । ७४ यङश्चाप् ५२८ । ७५ आवट्याच्च ५२९ । ७६ तद्धिताः ५३० ।
७७ यूनस्तिः ५३१ । ७८ अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ्गोत्रे ११९८ । ७९ गोत्रावयवात्
११९९ । ८० क्रौड्यादिभ्यश्च १२०० ॥ ४ ॥ ८१ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यो-
ऽन्यतरस्याम् १२०१ । ८२ समर्थानां प्रथमाद्वा १०७२ । ८३ प्राग्दीव्यतोऽण् १०७३ । ८४
अश्वपत्यादिभ्यश्च १०७४ । ८५ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः १०७७ । ८६ उत्सादिभ्यो-
ऽञ् १०७८ । ८७ स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् १०७९ । ८८ द्विगोर्लुगनपत्ये १०८० । ८९
गोत्रेऽलुगचि १०८१ । ९० यूनि लुक् १०८३ । ९१ फक्फिञोरन्यतरस्याम् १०८७ । ९२
तस्यापत्यम् १०८८ । ९३ एको गोत्रे १०९३ । ९४ गोत्राद्यून्यस्त्रियाम् १०९४ । ९५ अत
इञ् १०९५ । ९६ बाह्वादिभ्यश्च १०९६ । ९७ सुधातुरकङ् च १०९७ । ९८ गोत्रे कुञ्जादि-
भ्यश्च्फञ् १०९९ । ९९ नडादिभ्यः फक् ११०१ । १०० हरितादिभ्योऽञः ११०२ ॥ ५ ॥
१०१ यञिञोश्च ११०३ । १०२ शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु ११०४ । १०३ द्रोणपर्वत-
जीवन्तादन्यतरस्याम् ११०५ । १०४ अनृष्यानन्तर्ये बिदादिभ्योऽञ् ११०६ । १०५ गर्गा-
दिभ्यो यञ् ११०७ । १०६ मधुबभ्र्वोर्ब्राह्मणकौशिकयोः ११०९ । १०७ कपिबोधादाङ्गिरसे
१११० । १०८ वतण्डाच्च ११११ । १०९ लुक्स्त्रियाम् १११२ । ११० अश्वादिभ्यः फञ् १११३ ।
१११ भर्गात्त्रैगर्ते १११४ । ११२ शिवादिभ्योऽण् १११५ । ११३ अवृद्धाभ्यो नदीमानुषीभ्य-
स्तन्नामिकाभ्यः १११६ । ११४ ऋष्यन्धकवृष्णिकुरुभ्यश्च १११७ । ११५ मातुरुत्संख्यासंभद्र-
पूर्वायाः १११८ । ११६ कन्यायाः कनीन च १११९ । ११७ विकर्णशुङ्गच्छगलाद्वत्सभरद्वा-
जात्रिषु ११२० । ११८ पीलाया वा ११२१ । ११९ ढक्च मण्डूकात् ११२२ । १२० स्त्रीभ्यो
ढक् ११२३ ॥ ६ ॥ १२१ द्व्यचः ११२४ । १२२ इतश्चानिञः ११२५ । १२३ शुभ्रादिभ्यश्च
११२६ । १२४ विकर्णकुषीतकात्काश्यपे ११२७ । १२५ भ्रुवो वुक्च ११२८ । १२६ कल्या-
ण्यादीनामिनङ् ११३१ । १२७ कुलटाया वा ११३२ । १२८ चटकाया ऐरक् ११३४ । १२९
गोधाया ढ्रक् ११३५ । १३० आरगुदीचाम् ११३६ । १३१ क्षुद्राभ्यो वा ११३७ । १३२ पितृ-
ष्वसुश्छण् ११३८ । १३३ ढकि लोपः ११३९ । १३४ मातृष्वसुश्च ११४० । १३५ चतुष्पा-
द्भ्यो ढञ् ११४१ । १३६ गृष्ट्यादिभ्यश्च ११४३ । १३७ राजश्वशुराद्यत् ११५३ । १३८
क्षत्राद्घः ११६१ । १३९ कुलात्खः ११६२ । १४० अपूर्वपदादन्यतरस्यां यड्ढकञौ
११६३ ॥ ७ ॥ १४१ महाकुलादञ्खञौ ११६४ । १४२ दुष्कुलाड्ढक् ११६५ । १४३ स्वसुश्छः
११६६ । १४४ भ्रातुर्व्यच्च ११६७ । १४५ व्यन्सपत्ने ११६८ । १४६ रेवत्यादिभ्यष्ठक् ११६९ ।
१४७ गोत्रस्त्रियाः कुत्सने ण च ११७१ । १४८ वृद्धाट्ठक्सौवीरेषु बहुलम् ११७२ । १४९
फेश्छ च ११७३ । १५० फाण्टाहृतिमिमताभ्यां णफिञौ ११७४ । १५१ कुर्वादिभ्यो ण्यः ११७५ ।

१५२ सेनान्तलक्षणकारिभ्यश्च ११७६ । १५३ उदीचामिञ् ११७७ । १५४ तिकादिभ्यः फिञ् ११७८ । १५५ कौशल्यकार्मार्याभ्यां च ११७९ । १५६ अणो द्व्यचः ११८० । १५७ उदीचां वृद्धादगोत्रात् ११८१ । १५८ वाकिनादीनां कुक्च ११८२ । १५९ पुत्रान्तादन्यतरस्याम् ११८३ । १६० प्राचामवृद्धात्फिन्बहुलम् ११८४ ॥ ८ ॥ १६१ मनोर्जातावञ्यतौ षुक्च ११८५ । १६२ अपत्यं पौत्रप्रभृति गोत्रम् १०८९ । १६३ जीवति तु वंश्ये युवा १०९० । १६४ भ्रातरि च ज्यायसि १०९१ । १६५ वान्यस्मिन्सपिण्डे स्थविरतरे जीवति १०९२ । १६६ वृद्धस्य च पूजायाम् १०९२ (वा २६५५) । १६७ यूनश्च कुत्सायाम् १०९२ (वा २६५२) १६८ जनपदशब्दात्क्षत्रियादञ् ११८६ । १६९ साल्वेयगान्धारिभ्यां च ११८७ । १७० द्व्यञ्मगधकलिङ्गसूरमसादण् ११८८ । १७१ वृद्धेत्कोसलाजादाञ्ञ्यङ् ११८९ । १७२ कुरुनादिभ्यो ण्यः ११९० । १७३ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ११९१ । १७४ ते तद्राजाः ११९२ । १७५ कम्बोजाल्लुक् ११९४ । १७६ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ११९५ । १७७ अतश्च ११९६ । १७८ न प्राच्यभर्गादियौधेयादिभ्यः ११९७ ॥ ङ्याब्द्विगोः स्त्रिप्रौरादिवाहो दैवयज्ञियञिञोद्वर्चो महाकुलान्मनोर्जातावष्टादश ॥

द्वितीयः पादः ।

१ तेन रक्तं रागात् १२०२ । २ लाक्षारोचनाशकलकर्दमाट्ठक् १२०३ । ३ नक्षत्रेण युक्तः कालः १२०४ । ४ लुबविशेषे १२०५ । ५ संज्ञायां श्रवणाश्वत्थाभ्याम् १२०६ । ६ द्वन्द्वाच्छः १२०७ । ७ दृष्टं साम १२०८ । ८ कलेर्ढक् १२०९ (वा २६८९) ९ वामदेवाड्ड्यड्ड्यौ १२१० । १० परिवृतो रथः १२११ । ११ पाण्डुकम्बलादिनिः १२१२ । १२ द्वैपवैयाघ्रादञ् १२१३ । १३ कौमारापूर्ववचने १२१४ । १४ तत्रोद्धृतममत्रेभ्यः १२१५ । १५ स्थण्डिलाच्छयितरि व्रते १२१६ । १६ संस्कृतं भक्षाः १२१७ । १७ शूलोखाद्यत् १२१८ । १८ दध्नष्ठक् १२१९ । १९ उदश्वितोऽन्यतरस्याम् १२२० । २० क्षीराड्ढञ् १२२२ ॥ १ ॥ २१ सास्मिन्पौर्णमासीति संज्ञायाम् १२२३ । २२ आग्रहायण्यश्वत्थाट्ठक् १२२४ । २३ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः १२२५ । २४ सास्य देवता १२२६ । २५ कस्येत् १२२७ । २६ शुक्राद्घन् १२२८ । २७ अपोनप्त्रपांनप्तृभ्यां घः १२२९ । २८ छ च १२३० । २९ महेन्द्राद्घाणौ च १२३१ । ३० सोमाट्ट्यण् १२३२ । ३१ वाय्वृतुपित्रुषसो यत् १२३३ । ३२ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च १२३५ । ३३ अग्नेर्ढक् १२३६ । ३४ कालेभ्यो भववत् १२३७ । ३५ महाराजप्रोष्ठपदाट्ठञ् १२३८ । ३६ पितृव्यमातुलमातामहपितामहाः १२४२ । ३७ तस्य समूहः १२४३ । ३८ भिक्षादिभ्योऽण् १२४४ । ३९ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् १२४६ । ४० केदाराद्यञ्च १२४८ ॥ २ ॥ ४१ ठञ्कवचिनश्च १२४९ । ४२ ब्राह्मणमाणववाडवाद्यत् १२५० । ४३ ग्रामजनबन्धुसहायेभ्यस्तल् १२५१ । ४४ अनुदात्तादेरञ् १२५३ । ४५ खण्डिकादिभ्यश्च १२५४ । ४६ चरणेभ्यो धर्मवत् १२५५ । ४७ अचित्तहस्तिधेनोष्ठक् १२५६ । ४८ केशाश्वाभ्यां यञ्छावन्यतरस्याम् १२५७ । ४९ पाशादिभ्यो यः १२५८ । ५० खलगोरथात् १२५९ । ५१ इनित्रकट्यचश्च १२६० । ५२ विषयो देशे १२६१ । ५३ राजन्यादिभ्यो वुञ् १२६२ । ५४ भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ १२६३ । ५५ सोऽस्यादिरिति छन्दसः प्रगाथेषु १२६४ । ५६ संग्रामे प्रयोजनयोद्धृभ्यः १२६५ ।

५७ तदस्यां प्रहरणमिति क्रीडायां णः १२६६ । ५८ घञः सास्यां क्रियेति ञः १२६७ । ५९
तदधीते तद्वेद १२६९ । ६० क्रतूक्थादिसूत्रान्ताट्ठक् १२७० ॥ ३ ॥ ६१ क्रमादिभ्यो वुन् १२७१ ।
६२ अनुब्राह्मणादिनिः १२७२ । ६३ वसन्तादिभ्यष्ठक् १२७३ । ६४ प्रोक्ताल्लुक् १२७४ । ६५
सूत्राच्च कोपधात् १२७७ । ६६ छन्दोब्राह्मणानि च तद्विषयाणि १२७८ । ६७ तदस्मिन्नस्तीति
देशे तन्नाम्नि १२७९ । ६८ तेन निर्वृत्तम् १२८० । ६९ तस्य निवासः १२८१ । ७० अदूरभवश्च
१२८२ । ७१ ओरञ् १२८३ । ७२ मतोश्च बह्वजङ्गात् १२८४ । ७३ बह्वचः कूपेषु १२८५ ।
७४ उदक्च विपाशः १२८६ । ७५ संकलादिभ्यश्च १२८७ । ७६ स्त्रीषु सौवीरसाल्वप्राक्षु
१२८८ । ७७ सुवास्त्वादिभ्योऽण् १२८९ । ७८ रोणी १२९० । ७९ कोपधाच्च १२९१ । ८०
वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्म-
सखिसंकाशवलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः १२९२ ॥ ४ ॥ ८१ जनपदे लुप्
१२९३ । ८२ वरणादिभ्यश्च १३०१ । ८३ शर्कराया वा १३०२ । ८४ ठक्छौ च १३०३ । ८५
नद्यां मतुप् १३०४ । ८६ मध्वादिभ्यश्च १३०५ । ८७ कुमुदनडवेतसेभ्यो ड्मतुप् १३०६ । ८८
नडशादाड्ड्वलच् १३०७ । ८९ शिखाया वलच् १३०८ । ९० उत्करादिभ्यश्छः १३०९ । ९१
नडादीनां कुक्च १३१० । ९२ शेषे १३१२ । ९३ राष्ट्रावारपाराद्घखौ १३१३ । ९४ ग्रामाद्यखञौ
१३१४ । ९५ कत्त्र्यादिभ्यो ढकञ् १३१५ । ९६ कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु १३१६ । ९७
नद्यादिभ्यो ढक् १३१७ । ९८ दक्षिणापश्चात्पुरसस्त्यक् १३१८ । ९९ कापिश्याः ष्फक् १३१९ ।
१०० रङ्कोरमनुष्येऽण्च १३२० ॥ ५ ॥ १०१ द्युप्रागपागुदक्प्रतीचो यत् १३२१ । १०२
कन्यायाष्ठक् १३२२ । १०३ वर्णौ वुक् १३२३ । १०४ अव्ययात्त्यप् १३२४ । १०५ ऐषमोह्यः-
श्वसोऽन्यतरस्याम् १३२६ । १०६ तीररूप्योत्तरपदादञ्ञौ १३२७ । १०७ दिक्पूर्वपदादसंज्ञा-
यां ञः १३२८ । १०८ मद्रेभ्योऽञ् १३२९ । १०९ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् १३३० ।
११० प्रस्थोत्तरपदपलद्यादिकोपधादण् १३३१ । १११ कण्वादिभ्यो गोत्रे १३३२ । ११२ इञश्च
१३३३ । ११३ न द्व्यचः प्राच्यभरतेषु १३३४ । ११४ वृद्धाच्छः १३३७ । ११५ भवतष्ठक्छसौ
१३३९ । ११६ काश्यादिभ्यष्ठञ्ञिठौ १३४० । ११७ वाहीकग्रामेभ्यश्च १३४१ । ११८ विभा-
षोशीनरेषु १३४२ । ११९ ओर्देशे ठञ् १३४३ । १२० वृद्धात्प्राचाम् १३४४ ॥ ६ ॥ १२१ धन्वयो-
पधाद्वुञ् १३४५ । १२२ प्रस्थपुरवहान्ताच्च १३४६ । १२३ रोपधेतोः प्राचाम् १३४७ । १२४
जनपदतदवध्योश्च १३४८ । १२५ अवृद्धादपि बहुवचनविषयात् १३४९ । १२६ कच्छाग्निवक्त्रव-
र्तोत्तरपदात् १३५० । १२७ धूमादिभ्यश्च १३५१ । १२८ नगरात्कुत्सनप्रावीण्ययोः १३५२ ।
१२९ अरण्यान्मनुष्ये १३५३ । १३० विभाषा कुरुयुगंधराभ्याम् १३५४ । १३१ मद्रवृज्योः कन्
१३५५ । १३२ कोपधादण् १३५६ । १३३ कच्छादिभ्यश्च १३५७ । १३४ मनुष्यतत्स्थयोर्वुञ्
१३५८ । १३५ अपदातौ साल्वात् १३५९ । १३६ गोयवाग्वोश्च १३६० । १३७ गर्तोत्तरपदाच्छः
१३६१ । १३८ गहादिभ्यश्च १३६२ । १३९ प्राचां कटादेः १३६३ । १४० राज्ञः क च १३६४
॥ ७ ॥ १४१ वृद्धादकेकान्तखोपधात् १३६५ । १४२ कन्थापलदनगरग्रामह्रदोत्तरपदात् १३६६ ।
१४३ पर्वताच्च १३६७ । १४४ विभाषामनुष्ये १३६८ । १४५ कृकणपर्णाद्भारद्वाजे १३६९ ।
तेन सास्मिन्ठञ्क्रमादिभ्यो जनपदे द्युप्रागपाग्धन्ववृद्धात्पञ्च ॥

तृतीयः पादः ।

१ युष्मदस्मदोरन्यतरस्यां खञ्च १३७० । २ तस्मिन्नणि च युष्माकास्माकौ १३७१ । ३ तवकममकावेकवचने १३७२ । ४ अर्धाद्यत् १३७४ । ५ परावराधमोत्तमपूर्वाच्च १३७५ । ६ दिक्पूर्वपदाट्ठञ्च १३७६ । ७ ग्रामजनपदैकदेशादञ्ठञौ १३७७ । ८ मध्यान्मः १३७८ । ९ अ सांप्रतिके १३७९ ।१० द्वीपादनुसमुद्रं यञ् १३८०।११ कालाट्ठञ् १३८१ । १२ श्राद्धे शरदः १३८२ । १३ विभाषा रोगातपयोः १३८३ । १४ निशाप्रदोषाभ्यां च १३८४ । १५ श्वसस्तुट् च १३८५ । १६ संधिवेलाद्यृतुनक्षत्रेभ्योऽण १३८७ । १७ प्रावृष एण्यः १३८८ ।१८ वर्षाभ्यष्ठक् १३८९ । १९ छन्दसि ठञ् ३४५० ।२० वसन्ताच्च ३४५१ ॥ १ ॥ २१ हेमन्ताच्च ३४५२ । २२ सर्वत्राण्च तलोपश्च १३९० । २३ सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च १३९१ । २४ विभाषा पूर्वाह्णापराह्णाभ्याम् १३९२ । २५ तत्र जातः १३९३।२६ प्रावृषष्ठप् १३९४ ।२७ संज्ञाय शरदो वुञ् १३९५ । २८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् १४०१ । २९ पथः पन्थ च १४०२ । ३० अमावास्याया वा १४०३ ।३१ अ च १४०४ । ३२ सिन्ध्वपकराभ्यां कन् १४०५। ३३ अणञौ च १४०६ ।३४ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् १४०७।३५ स्थानान्तगोशालखरशालाच्च १४१०।३६ वत्सशालाभिजिदश्वयुक्छतभिषजो वा १४११ । ३७ नक्षत्रेभ्यो बहुलम् १४१२ । ३८ कृतलब्धक्रीतकुशलाः १४१३ । ३९ प्रायभवः १४१४ । ४० उपजानूपकर्णोपनीवेष्ठक् १४१५ ॥ २ ॥ ४१ संभूते १४१६ । ४२ कोशाड्ढञ् १४१७ । ४३ कालात्साधुपुष्प्यत्पच्यमानेषु १४१८ । ४४ उप्ते च १४१९ । ४५ आश्वयुज्या वुञ् १४२० । ४६ ग्रीष्मवसन्तादन्यतरस्याम् १४२१ । ४७ देयमृणे १४२२ । ४८ कलाप्यश्वत्थयवबुसाद्वुन् १४२३ । ४९ ग्रीष्मावरसमाद्वुञ् १४२४ । ५० संवत्सराग्रहायणीभ्यां ठञ्च १४२५। ५१ व्याहरति मृगः १४२६ ।५२ तदस्य सोढम् १४२७।५३ तत्र भवः १४२८ । ५४ दिगादिभ्यो यत् १४२९ । ५५ शरीरावयवाच्च १४३०।५६ दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् १४३३ । ५७ ग्रीवाभ्योऽण्च १४३४ । ५८ गम्भीराञ्ञ्यः १४३५ । ५९ अव्ययीभावाच्च १४३६ । ६० अन्तःपूर्वपदाट्ठञ् १४३७ ॥ ३ ॥ ६१ ग्रामात्पर्यनुपूर्वात् १४४० । ६२ जिह्वामूलाङ्गुलेश्छः १४४१ । ६३ वर्गान्ताच्च १४४२ । ६४ अशब्दे यत्खावन्यतरस्याम् १४४३ । ६५ कर्णललाटात्कनलंकारे १४४४ । ६६ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः १४४५ । ६७ बह्वचोऽन्तोदात्ताट्ठञ् १४४६ । ६८ क्रतुयज्ञेभ्यश्च १४४७ । ६९ अध्यायेष्वेवर्षेः १४४८ । ७० पौरोडाशपुरोडाशात्ष्ठन् १४४९ । ७१ छन्दसो यदणौ १४५० । ७२ द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् १४५१ । ७३ अणृगयनादिभ्यः १४५२ । ७४ तत आगतः १४५३ । ७५ ठगायस्थानेभ्यः १४५४ । ७६ शुण्डिकादिभ्योऽण् १४५५ । ७७ विद्यायोनिसंबन्धेभ्यो वुञ् १४५६ । ७८ ऋतष्ठञ् १४५७ । ७९ पितुर्यच्च १४५८ । ८० गोत्रादङ्कवत् १४५९ ॥ ४ ॥ ८१ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः १४६१ । ८२ मयट् च १४६२ । ८३ प्रभवति १४६३ । ८४ विदूराञ्ञ्यः १४६४ । ८५ तद्गच्छति पथिदूतयोः १४६५ । ८६ अभिनिष्क्रामति द्वारम् १४६६ । ८७ अधिकृत्य कृते ग्रन्थे १४६७ । ८८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः १४६८ । ८९ सोऽस्य निवासः १४६९ । ९० अभिजनश्च १४७० । ९१ आयुधजीविभ्यश्छः पर्वते १४७१ । ९२ शण्डिकादिभ्यो ञ्यः १४७२ ।

९३ सिन्धुतक्षशिलादिभ्योऽणञौ १४७३ । ९४ तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः १४७४ । ९५ भक्तिः १४७५ । ९६ अचित्ताददेशकालाट्ठक् १४७६ । ९७ महाराजाट्ठञ् १४७७ ९८ वासुदेवार्जुनाभ्यां वुन् १४७८ । ९९ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् १४७९ । १०० जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने १४८० ॥ ५ ॥ १०१ तेन प्रोक्तम् १४८१ । १०२ तित्तिरिवरतन्तुखण्डिकोखाच्छण् १४८२ । १०३ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः १४८३ । १०४ कलापिवैशम्पायनान्तेवासिभ्यश्च १४८४ । १०५ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु १४८५ । १०६ शौनकादिभ्यश्छन्दसि १४८६ । १०७ कठचरकाल्लुक् १४८७ । १०८ कलापिनोऽण् १४८८ । १०९ छगलिनो ढिनुक् १४८९ । ११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः १४९० । १११ कर्मन्दकृशाश्वादिनिः १४९१ । ११२ तेनैकदिक् १४९२ । ११३ तसिश्च १४९३ । ११४ उरसो यच्च १४९४ । ११५ उपज्ञाते १४९५ । ११६ कृते ग्रन्थे १४९६ । ११७ संज्ञायाम् १४९७ । ११८ कुलालादिभ्यो वुञ् १४९८ । ११९ क्षुद्राभ्रमरवटरपादपादञ् १४९९ । १२० तस्येदम् १५०० ॥ ६ ॥ १२१ रथाद्यत् १५०१ । १२२ पत्रपूर्वादञ् १५०२ । १२३ पत्राध्वर्युपरिषदश्च १५०३ । १२४ हलसीराट्ठक् १५०४ । १२५ द्वन्द्वाद्वुन्वैरमैथुनिकयोः १५०५ । १२६ गोत्रचरणाद्वुञ् १५०६ । १२७ संघाङ्कलक्षणेष्वञ्यञिञामण् १५०७ । १२८ शाकलाद्वा १५०८ । १२९ छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः १५०९ । १३० न दण्डमाणवान्तेवासिषु १५१० । १३१ रैवतिकादिभ्यश्छः १५११ । १३२ कौपिञ्जलहास्तिपदादण् १५१२(वा २९२१) । १३३ आथर्वणिकस्येकलोपश्च १५१३ । १३४ तस्य विकारः १५१४ । १३५ अवयवे च प्राण्योषधिवृक्षेभ्यः १५१५ । १३६ बिल्वादिभ्योऽण् १५१६ । १३७ कोपधाच्च १५१७ । १३८ त्रपुजतुनोः षुक् १५१८ । १३९ ओरञ् १५१९ । १४० अनुदात्तादेश्च १५२० ॥ ७ ॥ १४१ पलाशादिभ्यो वा १५२१ । १४२ शम्याः ष्लञ् १५२२ । १४३ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः १५२३ । १४४ नित्यं वृद्धशरादिभ्यः १५२४ । १४५ गोश्च पुरीषे १५२५ । १४६ पिष्टाच्च १५२६ । १४७ संज्ञायां कन् १५२७ । १४८ व्रीहेः पुरोडाशे १५२८ । १४९ असंज्ञायां तिलयवाभ्याम् १५२९ । १५० द्व्यचश्छन्दसि ३४५३ । १५१ नोत्वद्वर्ध्रबिल्वात् ३४५४ । १५२ तालादिभ्योऽण् १५३० । १५३ जातरूपेभ्यः परिमाणे १५३१ । १५४ प्राणिरजतादिभ्योऽञ् १५३२ । १५५ ञितश्च तत्प्रत्ययात् १५३३ । १५६ क्रीतवत्परिमाणात् १५३४ । १५७ उष्ट्राद्वुञ् १५३५ । १५८ उमोर्णयोर्वा १५३६ । १५९ एण्या ढञ् १५३७ । १६० गोपयसोर्यत् १५३८ ॥ ८ ॥ १६१ द्रोश्च १५३९ । १६२ माने वयः १५४० । १६३ फले लुक् १५४१ । १६४ प्लक्षादिभ्योऽण् १५४२ । १६५ जम्ब्वा वा १५४४ । १६६ लुप् च १५४५ । १६७ हरीतक्यादिभ्यश्च १५४६ । १६८ कंसीयपरशव्ययोर्यञञौ लुक्च १५४७ ॥ युष्मद्धेमन्तात्संभूते ग्रामाद्धेतुनेन रथात्पलाशादिभ्यो द्रोश्चाष्टौ ॥

चतुर्थः पादः ।

१ प्राग्वहतेष्ठक् १५४८ । २ तेन दीव्यति खनति जयति जितम् १५५० । ३ संस्कृतम् १५५१ । ४ कुलत्थकोपधादण् १५५२ । ५ तरति १५५३ । ६ गोपुच्छाट्ठञ् १५५४ । ७ नौद्व्यचष्ठन् १५५५ । ८ चरति १५५६ । ९ आकर्षात्ष्ठल् १५५७ । १० पर्पादिभ्यः ष्ठन् १५५८ । ११ श्वगणाट्ठञ्च १५५९ । १२ वेतनादिभ्यो जीवति १५६२ । १३ वस्नक्रयविक्रयाट्ठन् १५६३ ।

१४ आयुधाच्छ च १५६४ । १५ हरत्युत्सङ्गादिभ्यः १५६५ । १६ भस्त्रादिभ्यः ष्ठन् १५६६ । १७ विभाषा विवधवीवधात् १५६७ । १८ अण्कुटिलिकायाः १५६८ । १९ निर्वृत्तेऽक्षद्यूतादिभ्यः १५६९ । २० त्रेर्मम्नित्यम् १५७० ॥ १ ॥ २१ अपमित्ययाचिताभ्यां कक्कनौ १५७१ । २२ संसृष्टे १५७२ । २३ चूर्णादिनिः १५७३ । २४ लवणाल्लुक् १५७४ । २५ मुद्गादण् १५७५ । २६ व्यञ्जनैरुपसिक्ते १५७६ । २७ ओजःसहोऽम्भसा वर्तते १५७७ । २८ तत्प्रत्यनुपूर्वमीपलोमकूलम् १५७८ । २९ परिमुखं च १५७९ । ३० प्रयच्छति गर्ह्यम् १५८० । ३१ कुसीददशैकादशात्ष्ठन्ष्ठचौ १५८१ । ३२ उञ्छति १५८२ । ३३ रक्षति १५८३ । ३४ शब्ददर्दुरं करोति १५८४ । ३५ पक्षिमत्स्यमृगान्हन्ति १५८५ । ३६ परिपन्थं च तिष्ठति १५८६ । ३७ माथोत्तरपदपदव्यनुपदं धावति १५८७ । ३८ आक्रन्दाट्ठञ्च १५८८ । ३९ पदोत्तरपदं गृह्णाति १५८९ । ४० प्रतिकण्ठार्थललामं च १५९० ॥ २ ॥ ४१ धर्मं चरति १५९१ । ४२ प्रतिपथमेति ठंश्च १५९२ । ४३ समवायान्समवैति १५९३ । ४४ परिषदो ण्यः १५९४ । ४५ सेनाया वा १५९५ । ४६ संज्ञायां ललाटकुक्कुट्यौ पश्यति १५९६ । ४७ तस्य धर्म्यम् १५९७ । ४८ अण्महिष्यादिभ्यः १५९८ । ४९ ऋतोऽञ् १५९९ । ५० अवक्रयः १६०० । ५१ तदस्य पण्यम् १६०१ । ५२ लवणाट्ठञ् १६०२ । ५३ किसरादिभ्यः ष्ठन् १६०३ । ५४ शलालुनोऽन्यतरस्याम् १६०४ । ५५ शिल्पम् १६०५ । ५६ मड्डुकझर्झरादणन्यतरस्याम् १६०६ । ५७ प्रहरणम् १६०७ । ५८ परश्वधाट्ठञ्च १६०८ । ५९ शक्तियष्ट्योरीकक् १६०९ । ६० अस्तिनास्तिदिष्टं मतिः १६१० ॥ ३ ॥ ६१ शीलम् १६११ । ६२ छत्रादिभ्यो णः १६१२ । ६३ कर्माध्ययने वृत्तम् १६१४ । ६४ बह्वच्पूर्वपदाट्ठच् १६१५ । ६५ हितं भक्षाः १६१६ । ६६ तदस्मै दीयते नियुक्तम् १६१७ । ६७ श्राणामांसौदनाट्टिठन् १६१८ । ६८ भक्तादणन्यतरस्याम् १६१९ । ६९ तत्र नियुक्तः १६२० । ७० अगारान्ताट्ठन् १६२१ । ७१ अध्यायिन्यदेशकालात् १६२२ । ७२ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति १६२३ । ७३ निकटे वसति १६२४ । ७४ आवसथात्ष्ठल् १६२५ । ७५ प्राग्घिताद्यत् १६२६ । ७६ तद्वहति रथयुगप्रासङ्गम् १६२७ । ७७ धुरो यड्ढकौ १६२८ । ७८ खः सर्वधुरात् १६३० । ७९ एकधुराल्लुक्च १६३१ । ८० शकटादण् १६३२ ॥ ४ ॥ ८१ हलसीराट्ठक् १६३३ । ८२ संज्ञायां जन्या १६३४ । ८३ विध्यत्यधनुषा १६३५ । ८४ धनगणं लब्धा १६३६ । ८५ अन्नाण्णः १६३७ । ८६ वशं गतः १६३८ । ८७ पदमस्मिन्दृश्यम् १६३९ । ८८ मूलमस्याबर्हि १६४० । ८९ संज्ञायां धेनुष्या १६४१ । ९० गृहपतिना संयुक्ते ञ्यः १६४२ । ९१ नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु १६४३ । ९२ धर्मपथ्यर्थन्यायादनपेते १६४४ । ९३ छन्दसो निर्मिते १६४५ । ९४ उरसोऽण्च १६४६ । ९५ हृदयस्य प्रियः १६४७ । ९६ बन्धने चर्षौ १६४८ । ९७ मतजनहलात्करणजल्पकर्षेषु १६४९ । ९८ तत्र साधुः १६५० । ९९ प्रतिजनादिभ्यः खञ् १६५१ । १०० भक्ताण्णः १६५२ ॥ ५ ॥ १०१ परिषदो ण्यः १६५३ । १०२ कथादिभ्यष्ठक् १६५४ । १०३ गुडादिभ्यष्ठञ् १६५५ । १०४ पथ्यतिथिवसतिस्वपतेर्ढञ् १६५६ । १०५ सभाया यः १६५७ । १०६ ढश्छन्दसि ३४५५ । १०७ समानतीर्थे वासी १६५८ । १०८ समानोदरे शयित ओ चोदात्तः १६५९ । १०९ सोदराद्यः १६६० । ११० भवे छन्दसि ३४५६ । १११ पाथोनदीभ्यां ड्यण् ३४५७ । ११२ वेशन्तहिमवद्भ्यामण् ३४५८ । ११३ स्रोतसो विभाषा

उच्चहवौ ३४५९ । ११४ सगर्भसयूथसनुतायन् ३४६० । ११५ तुग्राद्घन् ३४६१ । ११६ अग्राद्यत् ३४६२ । ११७ घच्छौ च ३४६३ । ११८ समुद्राभ्राद्घः ३४६४ । ११९ बर्हिषि दत्तम् ३४६५ । १२० दूतस्य भागकर्मणी ३४६६ ॥ ६ ॥ १२१ रक्षोयातूनां हननी ३४६७ । १२२ रेवतीजगतीहविष्याभ्यः प्रशस्ये ३४६८ । १२३ असुरस्य स्वम् ३४६९ । १२४ मायायामण् ३४७० । १२५ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्च मतोः ३४७१ । १२६ अश्विमानण् ३४७२ । १२७ वयस्यासु मूर्ध्नो मतुप् ३४७३ । १२८ मत्वर्थे मासतन्वोः ३४७४ । १२९ मधोर्ञ च ३४७५ । १३० ओजसोऽहनि यत्खौ ३४७६ । १३१ वेशोयशआदेर्भगाद्यल् ३४७७ । १३२ ख च ३४७८ । १३३ पूर्वैः कृतमिनियौ च ३४७९ । १३४ अद्भिः संस्कृतम् ३४८० । १३५ सहस्रेण संमितौ घः ३४८१ । १३६ मतौ च ३४८२ । १३७ सोममर्हति यः ३४८३ । १३८ मये च ३४८४ । १३९ मधोः ३४८५ । १४० वसोः समूहे च ३५८६ ॥ ७ ॥ १४१ नक्षत्राद्घः ३४८७ । १४२ सर्वदेवात्तातिल् ३४८८ । १४३ शिवशमरिष्टस्य करे ३४८९ । १४४ भावे च ३४९० ॥ प्राग्वहतेरपमित्यधर्मे शीलं हलपरिषदो रक्षोनक्षत्राच्चत्वारि ॥

इति चतुर्थोऽध्यायः ।

पञ्चमोऽध्यायः ।

प्रथमः पादः ।

१ प्राक् क्रीताच्छः १६६१ । २ उगवादिभ्यो यत् १६६२ । ३ कम्बलाच्च संज्ञायाम् १६६३ । ४ विभाषा हविरपूपादिभ्यः १६६४ । ५ तस्मै हितम् १६६५ । ६ शरीरावयवाद्यत् १६६६ । ७ खलयवमाषतिलवृषब्रह्मणश्च १६६८ । ८ अजाविभ्यां थ्यन् १६६९ । ९ आत्मन्विश्वजनभोगोत्तरपदात्खः १६७० । १० सर्वपुरुषाभ्यां णढञौ १६७२ । ११ माणवचरकाभ्यां खञ् १६७३ । १२ तदर्थं विकृतेः प्रकृतौ १६७४ । १३ छदिरुपधिबलेर्ढञ् १६७५ । १४ ऋषभोपानहोर्ञ्यः १६७६ । १५ चर्मणोऽञ् १६७७ । १६ तदस्य तस्मिन्स्यादिति १६७८ । १७ परिखाया ढञ् १६७९ । १८ प्राग्वतेष्ठञ् १६८० । १९ आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् १६८१ । २० असमासे निष्कादिभ्यः १६८२ ॥ १ ॥ २१ शताच्च ठन्यतावशते १६८६ ॥ २२ संख्याया अतिशदन्तायाः कन् १६८७ । २३ वतोरिड्वा १६८८ । २४ विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् १६८९ । २५ कंसाट्टिठन् १६९० । २६ शूर्पादञन्यतरस्याम् १६९१ । २७ शतमानविंशतिकसहस्रवसनादण् १६९२ । २८ अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् १६९३ । २९ विभाषा कार्षापणसहस्राभ्याम् १६९४ । ३० द्वित्रिपूर्वान्निष्कात् १६९५ । ३१ बिस्ताच्च १६९६ । ३२ विंशतिकात्खः १६९७ । ३३ खार्या ईकन् १६९८ । ३४ पणपादमाषशताद्यत् १६९९ । ३५ शाणाद्वा १७०० । ३६ द्वित्रिपूर्वादण्च १७०१ । ३७ तेन क्रीतम् १७०२ । ३८ तस्य निमित्तं संयोगोत्पातौ १७०४ । ३९ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् १७०५ । ४० पुत्राच्छ च १७०६ ॥ २ ॥ ४१ सर्वभूमिपृथिवीभ्यामणञौ १७०७ । ४२ तस्येश्वरः १७०८ । ४३ तत्र विदित इति च १७०९ । ४४ लोकसर्वलोकाट्ठञ् १७१० । ४५ तस्य वापः १७११ । ४६ पात्रात्ष्ठन् १७१२ । ४७ तदस्मिन्वृद्ध्या-

यलाभशुल्कोपदा दीयते १७१३ । ४८ पूरणार्धाट्ठन् १७१४ । ४९ भागाद्यच्च १७१५ । ५० तद्धरति वहत्यावहति भाराद्वंशादिभ्यः १७१६ । ५१ वस्नद्रव्याभ्यां ठन्कनौ १७१७ । ५२ संभवत्यवहरति पचति १७१८ । ५३ आढकाचितपात्रात्खोऽन्यतरस्याम् १७१९ । ५४ द्विगोः ष्ठंश्च १७२० । ५५ कुलिजाल्लुक्खौ च १७२१ । ५६ सोऽस्यांशवस्नभृतयः १७२२ । ५७ तदस्य परिमाणम् १७२३ । ५८ संख्यायाः संज्ञासंघसूत्राध्ययनेषु १७२४ । ५९ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् १७२५ । ६० पञ्चद्दशतौ वर्गे वा १७२६ ॥३॥ ६१ सप्तनोऽञ्छन्दसि ३४९१ । ६२ त्रिंशच्चत्वारिंशतो ब्राह्मणे संज्ञायां डण् १७२७ । ६३ तदर्हति १७२८ । ६४ छेदादिभ्यो नित्यम् १७२९ । ६५ शीर्षच्छेदाद्यच्च १७३० । ६६ दण्डादिभ्यो यः १७३१ । ६७ छन्दसि च ३४९२ । ६८ पात्राद्घंश्च १७३२ । ६९ कडंकरदक्षिणाच्छ च १७३३ । ७० स्थालीबिलात् १७३४ । ७१ यज्ञर्त्विग्भ्यां घखञौ १७३५ । ७२ पारायणतुरायणचान्द्रायणं वर्तयति १७३६ । ७३ संशयमापन्नः १७३७ । ७४ योजनं गच्छति १७३८ । ७५ पथः ष्कन् १७३९ । ७६ पन्थो ण नित्यम् १७४० । ७७ उत्तरपथेनाहृतं च १७४१ । ७८ कालात् १७४२ । ७९ तेन निर्वृत्तम् १७४३ । ८० तमधीष्टो भृतो भूतो भावी १७४४ ॥ ४ ॥ ८१ मासाद्वयसि यत्खञौ १७४५ । ८२ द्विगोर्यप् १७४६ । ८३ षण्मासाण्ण्यच्च १७४७ । ८४ अवयसि ठंश्च १७४८ । ८५ समायाः खः १७४९ । ८६ द्विगोर्वा १७५० । ८७ रात्र्यहःसंवत्सराच्च १७५१ । ८८ वर्षाल्लुक्च १७५३ । ८९ चित्तवति नित्यम् १७५५ । ९० षष्टिकाः षष्टिरात्रेण पच्यन्ते १७५६ । ९१ वत्सरान्ताच्छश्छन्दसि ३४९३ । ९२ संपरिपूर्वात्ख च ३४९४ । ९३ तेन परिजय्यलभ्यकार्यसुकरम् १७५७ । ९४ तदस्य ब्रह्मचर्यम् १७५८ । ९५ तस्य च दक्षिणा यज्ञाख्येभ्यः १७५९ । ९६ तत्र च दीयते कार्यं भववत् १७६० । ९७ व्युष्टादिभ्योऽण् १७६१ । ९८ तेन यथाकथाचहस्ताभ्यां णयतौ १७६२ । ९९ संपादिनि १७६३ । १०० कर्मवेषाद्यत् १७६४ ॥५॥ १०१ तस्मै प्रभवति संतापादिभ्यः १७६५ । १०२ योगाद्यच्च १७६६ । १०३ कर्मण उकञ् १७६७ । १०४ समयस्तदस्य प्राप्तम् १७६८ । १०५ ऋतोरण् १७६९ । १०६ छन्दसि घस् ३४९५ । १०७ कालाद्यत् १७७० । १०८ प्रकृष्टे ठञ् १७७१ । १०९ प्रयोजनम् १७७२ । ११० विशाखाषाढादण्मन्थदण्डयोः १७७३ । १११ अनुप्रवचनादिभ्यश्छः १७७४ । ११२ समापनात्सपूर्वपदात् १७७५ । ११३ ऐकागारिकट् चौरे १७७६ । ११४ आकालिकडाद्यन्तवचने १७७७ । ११५ तेन तुल्यं क्रिया चेद्वतिः १७७८ । ११६ तत्र तस्येव १७७९ । ११७ तदर्हम् १७८० । ११८ उपसर्गाच्छन्दसि धात्वर्थे ३४९६ । ११९ तस्य भावस्त्वतलौ १७८१ । १२० आ च

त्वात् १७८२ ॥ ६ ॥ १२१ न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः १७८३ । १२२ पृथ्वादिभ्य इमनिज्वा १७८४ । १२३ वर्णदृढादिभ्यः ष्यञ्च १७८७ । १२४ गुणवचनब्राह्मणादिभ्यः कर्मणि च १७८८ । १२५ स्तेनाद्यन्नलोपश्च १७९० । १२६ सख्युर्यः १७९१ । १२७ कपिज्ञात्योर्ढक् १७९२ । १२८ पत्यन्तपुरोहितादिभ्यो यक् १७९३ । १२९ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् १७९४ । १३० हायनान्तयुवादिभ्योऽण् १७९५ । १३१ इगन्ताच्च लघुपूर्वात् १७९६ । १३२ योपधाद्गुरूपोत्तमाद्वुञ् १७९७ । १३३ द्वन्द्वमनोज्ञादिभ्यश्च १७९८ । १३४ गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु

१७९९ । १३५ होत्राभ्यश्छः १८०० । १३६ ब्रह्मणस्त्वः १८०१ ॥ प्राक् क्रीताच्छताच्च संव-भूमिसततनोऽन्मासात्तस्मै प्रभवति न नञ्पूर्वात्षोडश ॥

द्वितीयः पादः ।

१ धान्यानां भवने क्षेत्रे खञ् १८०२ । २ व्रीहिशाल्योर्ढक् १८०३ । ३ यवयवकषष्टिकाद्यत् १८०४ । ४ विभाषा तिलमाषोमाभङ्गाणुभ्यः १८०५ । ५ सर्वचर्मणः कृतः खखञौ १८०६ । ६ यथामुखसंमुखस्य दर्शनः खः १८०७ । ७ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति १८०८ । ८ आप्रपदं प्राप्नोति १८०९ । ९ अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु १८१० । १० परोवर-परंपरपुत्रपौत्रमनुभवति १८११ । ११ अवारपारात्यन्तानुकामं गामी १८१२ । १२ समांसमां विजायते १८१३ । १३ अद्यश्वीनावष्टब्धे १८१४ । १४ आगवीनः १८१५ । १५ अनुग्वलं-गामी १८१६ । १६ अध्वनो यत्खौ १८१७ । १७ अभ्यमित्राच्छ च १८१८ । १८ गोष्ठात्खञ्भूतपूर्वे १८१९ । १९ अश्वस्यैकाहगमः १८२० । २० शालीनकौपीने अधृष्टा-कार्ययोः १८२१ ॥ १ ॥ २१ व्रातेन जीवति १८२२ । २२ सातपदीनं सख्यम् १८२३ । २३ हैयङ्गवीनं संज्ञायाम् १८२४ । २४ तस्य पाकमूले पील्वादिकर्णा-दिभ्यः कुणब्जाहचौ १८२५ । २५ पक्षात्तिः १८२६ । २६ तेन वित्तश्चुञ्चुप्चणपौ १८२७ । २७ विनञ्भ्यां नानाञौ न सह १८२८ । २८ वेः शालच्छङ्कटचौ १८२९ । २९ संप्रोदश्च कटच् १८३० । ३० अवात्कुटारच्च १८३१ । ३१ नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः १८३२ । ३२ नेर्बिडज्बिरीसचौ १८३३ । ३३ इन-च्पिटच्चिकचि च १८३४ । ३४ उपाधिभ्यां त्यकन्नासन्नारूढयोः १८३५ । ३५ कर्मणि घटोऽठच् १८३६ । ३६ तदस्य संजातं तारकादिभ्य इतच् १८३७ । ३७ प्रमाणे द्वयसज्दघ्नञ्मात्रचः १८३८ । ३८ पुरुषहस्तिभ्यामण्च १८३९ । ३९ यत्तदेतेभ्यः परिमाणे वतुप् १८४० । ४० किमिदंभ्यां वो घः १८४१ ॥ २ ॥ ४१ किमः संख्यापरिमाणे डति च १८४२ । ४२ संख्याया अवयवे तयप् १८४३ । ४३ द्वित्रिभ्यां तयस्यायज्वा १८४४ । ४४ उभादुदात्तो नित्यम् १८४५ । ४५ तदस्मिन्नधिकमिति दशान्ताड्डः १८४६ । ४६ शद-न्तविंशतेश्च १८४७ । ४७ संख्याया गुणस्य निमाने मयट् १८४८ । ४८ तस्य पूरणे डट् १८४९ । ४९ नान्तादसंख्यादेर्मट् १८५० । ५० थट् च च्छन्दसि ३४९७ । ५१ षट्कतिकतिपयचतुरां थुक् १८५१ । ५२ बहुपूग-गणसंघस्य तिथुक् १८५२ । ५३ वतोरिथुक् १८५३ । ५४ द्वेस्तीयः १८५४ । ५५ त्रेः संप्र-सारणं च १८५५ । ५६ विंशत्यादिभ्यस्तमडन्यतरस्याम् १८५६ । ५७ नित्यं शतादिमासार्ध-माससंवत्सराच्च १८५७ । ५८ षष्ट्यादेश्चासंख्यादेः १८५८ । ५९ मतौ छः सूक्तसाम्नोः १८५९ । ६० अध्यायानुवाकयोर्लुक् १८६० ॥ ३ ॥ ६१ विमुक्तादिभ्योऽण् १८६१ । ६२ गोषदादिभ्यो वुन् १८६२ । ६३ तत्र कुशलः पथः १८६३ । ६४ आकर्षादिभ्यः कन् १८६४ । ६५ धनहि-रण्यात्कामे १८६५ । ६६ स्वाङ्गेभ्यः प्रसिते १८६६ । ६७ उदराट्ठगाद्यूने १८६७ । ६८ सस्येन परिजातः १८६८ । ६९ अंशं हारी १८६९ । ७० तन्त्रादचिरापहृते १८७० । ७१ ब्राह्मणको-ष्णिके संज्ञायाम् १८७१ । ७२ शीतोष्णाभ्यां कारिणि १८७२ । ७३ अधिकम् १८७३ । ७४ अनुकाभिकाभीकः कमिता १८७४ । ७५ पार्श्वेनान्विच्छति १८७५ । ७६ अयःशूलदण्डाजि-

नाभ्यां ठक्ठञौ १८७६ । ७७ तावतिथं ग्रहणमिति लुग्वा १८७७ । ७८ स एषां ग्रामणीः १८७८ । ७९ शृङ्खलमस्य बन्धनं करभे १८७९ । ८० उत्क उन्मनाः १८८० ॥ ४ ॥ ८१ कालप्रयोजनाद्रोगे १८८१ । ८२ तदस्मिन्नन्नं प्रायेण संज्ञायाम् १८८२ । ८३ कुल्माषादञ् १८८३ । ८४ श्रोत्रियश्छन्दोऽधीते १८८४ । ८५ श्राद्धमनेन भुक्तमिनिठनौ १८८५ । ८६ पूर्वादिनिः १८८६ । ८७ सपूर्वाच्च १८८७ । ८८ इष्टादिभ्यश्च १८८८ । ८९ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि १८८९ । ९० अनुपद्यन्वेष्टा १८९० । ९१ साक्षाद्द्रष्टरि संज्ञायाम् १८९१ । ९२ क्षेत्रियच्परक्षेत्रे चिकित्स्यः १८९२ । ९३ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा १८९३ । ९४ तदस्यास्त्यस्मिन्निति मतुप् १८९४ । ९५ रसादिभ्यश्च १८९५ । ९६ प्राणिस्थादातो लजन्यतरस्याम् १९०३ । ९७ सिध्मादिभ्यश्च १९०४ । ९८ वत्सांसाभ्यां कामबले १९०५ । ९९ फेनादिलच्च १९०६ । १०० लोमादिपामादिपिच्छादिभ्यः शनेलचः १९०७ ॥ ५ ॥ १०१ प्रज्ञाश्रद्धार्चाभ्यो णः १९०८ । १०२ तपःसहस्राभ्यां विनीनी १९०९ । १०३ अण्च १९१० । १०४ सिकताशर्कराभ्यां च १९११ । १०५ देशे लुबिलचौ च १९१२ । १०६ दन्त उन्नत उरच् १९१३ । १०७ ऊषसुषिमुष्कमधो रः १९१४ । १०८ द्युद्रुभ्यां मः १९१५ । १०९ केशाद्वोऽन्यतरस्याम् १९१६ । ११० गाण्ड्यजगात्संज्ञायाम् १९१७ । १११ काण्डाण्डादीरन्नीरचौ १९१८ । ११२ रजःकृष्यासुतिपरिषदो वलच् १९१९ । ११३ दन्तशिखात्संज्ञायाम् १९२० । ११४ ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः १९२१ । ११५ अत इनिठनौ १९२२ । ११६ व्रीह्यादिभ्यश्च १९२३ । ११७ तुन्दादिभ्य इलच्च १९२४ । ११८ एकगोपूर्वाट्ठञ्नित्यम् १९२५ । ११९ शतसहस्रान्ताच्च निष्कात् १९२६ । १२० रूपादाहतप्रशंसयोर्यप् १९२७ ॥ ६ ॥ १२१ अस्मायामेधास्रजो विनिः १९२८ । १२२ बहुलं छन्दसि ३४९८ । १२३ ऊर्णाया युस् १९२९ । १२४ वाचो ग्मिनिः १९३० । १२५ आलजाटचौ बहुभाषिणि १९३१ । १२६ स्वामिन्नैश्वर्ये १९३२ । १२७ अर्शआदिभ्योऽच् १९३३ । १२८ द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः १९३४ । १२९ वातातीसाराभ्यां कुक्च १९३५ । १३० वयसि पूरणात् १९३६ । १३१ सुखादिभ्यश्च १९३७ । १३२ धर्मशीलवर्णान्ताच्च १९३८ । १३३ हस्ताज्जातौ १९३९ । १३४ वर्णाद्ब्रह्मचारिणि १९४० । १३५ पुष्करादिभ्यो देशे १९४१ । १३६ बलादिभ्यो मतुबन्यतरस्याम् १९४२ । १३७ संज्ञायां मन्माभ्याम् १९४३ । १३८ कंशंभ्यां बभयुस्तितुतयसः १९४४ । १३९ तुन्दिवलिवटेर्भः १९४५ । १४० अहंशुभमोर्युस् १९४६ ॥ ७ ॥ धान्यानां व्रातेन किमो विमुक्तादिभ्यो कालप्रयोजनात्प्रज्ञाश्रद्धास्मायामेधार्विंशतिः ॥

तृतीयः पादः ।

१ प्राग्दिशो विभक्तिः १९४७ । २ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः १९४८ । ३ इदम इश् १९४९ । ४ एतेतौ रथोः १९५० । ५ एतदोऽन् १९५१ । ६ सर्वस्य सोऽन्यतरस्यां दि १९५२ । ७ पञ्चम्यास्तसिल् १९५३ । ८ तसेश्च १९५५ । ९ पर्यभिभ्यां च १९५६ । १० सप्तम्यास्त्रल् १९५७ । ११ इदमो हः १९५८ । १२ किमोऽत् १९५९ । १३ वा ह च च्छन्दसि १९६१ । १४ इतराभ्योऽपि दृश्यन्ते १९६२ । १५ सर्वैकान्यकिंयत्तदः काले दा १९६४ । १६ इदमो र्हिल् १९६५ । १७ अधुना १९६६ । १८ दानीं च १९६७ । १९

तदो दा च १९६८ । २० तयोर्दार्हिलौ च च्छन्दसि ३४९९ ॥ १ ॥ २१ अनद्यतने र्हिलन्यतरस्याम् १९६९ । २२ सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः १९७० । २३ प्रकारवचने थाल् १९७१ । २४ इदमस्थमुः १९७२ । २५ किमश्च १९७३ । २६ था हेतौ च च्छन्दसि ३५०० । २७ दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः १९७४ । २८ दक्षिणोत्तराभ्यामतसुच् १९७८ । २९ विभाषा परावराभ्याम् १९७९ । ३० अञ्चेर्लुक् १९८० । ३१ उपर्युपरिष्टात् १९८१ । ३२ पश्चात् १९८२ । ३३ पश्च पश्चा च च्छन्दसि ३५०१ । ३४ उत्तराधरदक्षिणादातिः १९८३ । ३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः १९८४ । ३६ दक्षिणादाच् १९८५ । ३७ आहि च दूरे १९८६ । ३८ उत्तराच्च १९८७ । ३९ पूर्वाधरावराणामसि पुरधवश्चैषाम् १९७५ । ४० अस्ताति च १९७६ ॥ २ ॥ ४१ विभाषावरस्य १९७७ । ४२ संख्याया विधार्थे धा १९८८ । ४३ अधिकरणविचाले च १९८९ । ४४ एकाद्धो ध्यमुञन्यतरस्याम् १९९० । ४५ द्वित्र्योश्च धमुञ् १९९१ । ४६ एधाच्च १९९२ । ४७ याप्ये पाशप् १९९३ । ४८ पूरणाद्भागे तीयादन् १९९४ । ४९ प्रागेकादशभ्योऽच्छन्दसि १९९५ । ५० षष्ठाष्टमाभ्यां ञ च १९९६ । ५१ मानपश्वङ्गयोः कन्लुकौ च १९९७ । ५२ एकादाकिनिच्चासहाये १९९८ । ५३ भूतपूर्वे चरट् १९९९ । ५४ षष्ठ्या रूप्य च २००० । ५५ अतिशायने तमबिष्ठनौ २००१ । ५६ तिङश्च २००२ । ५७ द्विवचनविभज्योपपदे तरबीयसुनौ २००५ । ५८ अजादी गुणवचनादेव २००६ । ५९ तुश्छन्दसि २००७ । ६० प्रशस्यस्य श्रः २००९ ॥ ३ ॥ ६१ ज्य च २०११ । ६२ वृद्धस्य च २०१३ । ६३ अन्तिकबाढयोर्नेदसाधौ २०१४ । ६४ युवाल्पयोः कनन्यतरस्याम् २०१९ । ६५ विन्मतोर्लुक् २०२० । ६६ प्रशंसायां रूपप् २०२१ । ६७ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः २०२२ । ६८ विभाषा सुपो बहुच्पुरस्तात्तु २०२३ । ६९ प्रकारवचने जातीयर् २०२४ । ७० प्रागिवात्कः २०२५ । ७१ अव्ययसर्वनाम्नामकच्प्राक्टेः २०२६ । ७२ कस्य च दः २०२७ । ७३ अज्ञाते २०२८ । ७४ कुत्सिते २०२९ । ७५ संज्ञायां कन् २०३० । ७६ अनुकम्पायाम् २०३१ । ७७ नीतौ च तद्युक्तात् २०३२ । ७८ बह्वचो मनुष्यनाम्नष्ठज्वा २०३३ । ७९ घनिलचौ च २०३४ । ८० प्राचामुपादेरडज्वुचौ च २०३६ ॥ ४ ॥ ८१ जातिनाम्नः कन् २०३७ । ८२ अजिनान्तस्योत्तरपदलोपश्च २०३९ । ८३ ठाजादावूर्ध्वं द्वितीयादचः २०३५ । ८४ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् २०३८ । ८५ अल्पे २०४० । ८६ ह्रस्वे २०४१ । ८७ संज्ञायां कन् २०४२ । ८८ कुटीशमीशुण्डाभ्यो रः २०४३ । ८९ कुत्वा डुपच् २०४४ । ९० कासूगोणीभ्यां ष्टरच् २०४५ । ९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे २०४६ । ९२ कियत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् २०४७ । ९३ वा बहूनां जातिपरिप्रश्ने डतमच् २०४८ । ९४ एकाच्च प्राचाम् २०४९ । ९५ अवक्षेपणे कन् २०५० । ९६ इवे प्रतिकृतौ २०५१ । ९७ संज्ञायां च २०५२ । ९८ लुम्मनुष्ये २०५३ । ९९ जीविकार्थे चापण्ये २०५४ । १०० देवपथादिभ्यश्च २०५५ ॥ ५ ॥ १०१ वस्तेर्ढञ् २०५६ । १०२ शिलाया ढः २०५७ । १०३ शाखादिभ्यो यः २०५८ । १०४ द्रव्यं च भव्ये २०५९ । १०५ कुशाग्राच्छः २०६० । १०६ समासाच्च तद्विषयात् २०६१ । १०७ शर्करादिभ्योऽण् २०६२ । १०८ अङ्गुल्यादिभ्यष्ठक् २०६३ । १०९ एकशालायाष्ठजन्यत-

रस्याम् २०६४। ११० कर्कलोहितादीकक् २०६५। १११ प्रत्नपूर्वविश्वेमात्थाल्छन्दसि ३५०२। ११२ पूगाञ्ञ्योऽग्रामणीपूर्वात् २०६६। ११३ व्रातच्फञोरस्त्रियाम् ११००। ११४ आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् २०६७। ११५ वृकाट्टेण्यण् २०६८। ११६ दामन्यादित्रिगर्तषष्ठाच्छः २०६९। ११७ पर्श्वादियौधेयादिभ्योऽणञौ २०७०। ११८ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् २०७१। ११९ ञ्यादयस्तद्राजाः २०७२। प्राग्दिशोऽनद्यतने विभाषाऽज्य त्र जातिनाम्नो वस्तेरेकोनविंशतिः॥

चतुर्थः पादः।

१ पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च २०७३। २ दण्डव्यवसर्गयोश्च २०७४। ३ स्थूलादिभ्यः प्रकारवचने कन् २०७५। ४ अनत्यन्तगतौ क्तात् २०७६। ५ न सामिवचने २०७७। ६ बृहत्या आच्छादने २०७८। ७ अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः २०७९। ८ विभाषाञ्चेरदिक्स्त्रियाम् २०८०। ९ जात्यन्ताच्छ बन्धुनि २०८१। १० स्थानान्ताद्विभाषा सस्थानेनेति चेत् २०८२। ११ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे २००४। १२ अमु च च्छन्दसि ३५०३। १३ अनुगादिनष्ठक् २०८३। १४ णचः स्त्रियामञ् ३२१६। १५ अणिनुणः ३२१९। १६ विसारिणो मत्स्ये २०८४। १७ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् २०८५। १८ द्वित्रिचतुर्भ्यः सुच् २०८६। १९ एकस्य सकृच्च २०८७। २० विभाषा बहोर्धाऽविप्रकृष्टकाले २०८८॥ १॥ २१ तत्प्रकृतवचने मयट् २०८९। २२ समूहवच्च बहुषु २०९०। २३ अनन्तावसथेतिहभेषजाञ्ञ्यः २०९१। २४ देवतान्तात्तादर्थ्ये यत् २०९२। २५ पादार्घाभ्यां च २०९३। २६ अतिथेर्ञ्यः २०९४। २७ देवात्तल् २०९५। २८ अवेः कः २०९६। २९ यावादिभ्यः कन् २०९७। ३० लोहितान्मणौ २०९८। ३१ वर्णे चानित्ये २०९९। ३२ रक्ते २१००। ३३ कालाच्च २१०१। ३४ विनयादिभ्यष्ठक् २१०२। ३५ वाचो व्याहृतार्थायाम् २१०३। ३६ तद्युक्तात्कर्मणोऽण् २१०४। ३७ ओषधेरजातौ २१०५। ३८ प्रज्ञादिभ्यश्च २१०६। ३९ मृदस्तिकन् २१०७। ४० सस्नौ प्रशंसायाम् २१०८॥ २॥ ४१ वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ३५०४। ४२ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् २१०९। ४३ संख्यैकवचनाच्च वीप्सायाम् २११०। ४४ प्रतियोगे पञ्चम्यास्तसिः २१११। ४५ अपादाने चाहीयरुहोः २११२। ४६ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः २११३। ४७ हीयमानपापयोगाच्च २११४। ४८ षष्ठ्या व्याश्रये २११५। ४९ रोगाच्चापनयने २११६। ५० अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः २११७। ५१ अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च २१२१। ५२ विभाषा साति कार्त्स्न्ये २१२२। ५३ अभिविधौ संपदा च २१२४। ५४ तदधीनवचने २१२५। ५५ देये त्रा च २१२६। ५६ देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् २१२७। ५७ अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् २१२८। ५८ कृञो द्वितीयतृतीयशम्बबीजात्कृषौ २१२९। ५९ संख्यायाश्च गुणान्तायाः २१३०। ६० समयाच्च यापनायाम् २१३१॥ ३॥ ६१ सपत्रनिष्पत्रादतिव्यथने २१३२। ६२ निष्कुलान्निष्कोषणे २१३३। ६३ सुखप्रियादानुलोम्ये २१३४। ६४ दुःखात्प्रातिलोम्ये २१३५। ६५ शूलात्पाके २१३६। ६६ सत्यादशपथे २१३७। ६७ मद्रात्परिवापणे २१३८। ६८ समासान्ताः ६७६। ६९ न पूजनात् ९५४। ७० किमः क्षेपे ९५५। ७१ नञस्तत्पुरुषात् ९५६। ७२

पथो विभाषा ९५७ । ७३ बहुव्रीहौ संख्येये डजबहुगणात् ८५१ । ७४ ऋक्पूरब्धूःपथामानक्षे ९४० । ७५ अच्प्रत्यन्ववपूर्वात्सामलोम्नः ९४३ । ७६ अक्ष्णोऽदर्शनात् ९४४ । ७७ अचतुर-विचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवा-हर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ९४५ । ७८ ब्रह्महस्तिभ्यां वर्चसः ९४६ । ७९ अवसमन्धेभ्यस्तमसः ९४७ । ८० श्वसो वसीयःश्रेयसः ९४८ ॥ ४ ॥ ८१ अन्ववतप्ताद्रहसः ९४९ । ८२ प्रतेरुरसः सप्तमीस्थात् ९५० । ८३ अनुग-वमायामे ९५१ । ८४ द्विस्तावा त्रिस्तावा वेदिः ९५२ । ८५ उपसर्गादध्वनः ९५३ । ८६ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ७८६ । ८७ अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः ७८७ । ८८ अह्नोऽह्न एतेभ्यः ७९० । ८९ न संख्यादेः समाहारे ७९३ । ९० उत्तमैकाभ्यां च ७९४ । ९१ राजाहःसखिभ्यष्टच् ७८८ । ९२ गोरतद्धितलुकि ७२९ । ९३ अग्राख्यायामुरसः ७९५ । ९४ अनोश्मायःसरसां जातिसंज्ञयोः ७९६ । ९५ ग्रामकौटाभ्यां च तक्ष्णः ७९७ । ९६ अतेः शुनः ७९८ । ९७ उपमानादप्राणिषु ७९९ । ९८ उत्तरमृगपूर्वाच्च सक्थ्नः ८०० । ९९ नावो द्विगोः ८०१ । १०० अर्धाच्च ८०२ ॥ ५ ॥ १०१ खार्याः प्राचाम् ८०३ । १०२ द्वित्रिभ्याम ञ्जलेः ८०४ । १०३ अनसन्तान्नपुंसकाच्छन्दसि ३५०५ । १०४ ब्रह्मणो जानपदाख्यायाम् ८०५ । १०५ कुमहद्भ्यामन्यतरस्याम् ८०६ । १०६ द्वन्द्वाच्चुदषहान्तात्समाहारे ९३० । १०७ अव्य-यीभावे शरत्प्रभृतिभ्यः ६७७ । १०८ अनश्च ६७८ । १०९ नपुंसकादन्यतरस्याम् ६८० । ११० नदीपौर्णमास्याग्रहायणीभ्यः ६८१ । १११ झयः ६८२ । ११२ गिरेश्च सेनकस्य ६८३ । ११३ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् ८५२ । ११४ अङ्गुलेर्दारुणि ८५३ । ११५ द्वित्रिभ्यां ष मूर्ध्नः ८५४ । ११६ अप्पूरणीप्रमाण्योः ८३२ । ११७ अन्तर्बहिर्भ्यां च लोम्नः ८५५ । ११८ अञ्नासिकायाः संज्ञायां नसं चास्थूलात् ८५६ । ११९ उपसर्गाच्च ८५८ । १२० सुप्रातसुश्व-सुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ८६० ॥ ६ ॥ १२१ नञ्दुःसुभ्यो हलिसक्थ्योरन्य-तरस्याम् ८६१ । १२२ नित्यमसिच्प्रजामेधयोः ८६२ । १२३ बहुप्रजाश्छन्दसि ३५०६ । १२४ धर्मादनिच्केवलात् ८६३ । १२५ जम्भा सुहरिततृणसोमेभ्यः ८६४ । १२६ दक्षिणेर्मा लुब्धयोगे ८६५ । १२७ इच्कर्मव्यतिहारे ८६६ । १२८ द्विदण्ड्यादिभ्यश्च ८६७ । १२९ प्रसं-भ्यां जानुनोर्ज्ञुः ८६८ । १३० ऊर्ध्वाद्विभाषा ८६९ । १३१ ऊधसोऽनङ् ४८३ । १३२ धनुषश्च ८७० । १३३ वा संज्ञायाम् ८७१ । १३४ जायाया निङ् ८७२ । १३५ गन्धस्येदुत्पूतिसुसुर-भिभ्यः ८७४ । १३६ अल्पाख्यायाम् ८७५ । १३७ उपमानाच्च ८७६ । १३८ पादस्य लोपो-ऽहस्त्यादिभ्यः ८७७ । १३९ कुम्भपदीषु च ८७८ । १४० संख्यासुपूर्वस्य ८७९ ॥ ७ ॥ १४१ वयसि दन्तस्य दतृ ८८० । १४२ छन्दसि च ३५०७ । १४३ स्त्रियां संज्ञायाम् ८८१ । १४४ विभाषा श्यावारोकाभ्याम् ८८२ । १४५ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ८८३ । १४६ ककुद-स्यावस्थायां लोपः ८८४ । १४७ त्रिककुत्पर्वते ८८५ । १४८ उद्विभ्यां काकुदस्य ८८६ । १४९ पूर्णाद्विभाषा ८८७ । १५० सुहृद्दुर्हृदौ मित्रामित्रयोः ८८८ । १५१ उरःप्रभृतिभ्यः कप् ८८९ । १५२ इनः स्त्रियाम् ८९० । १५३ नद्यृतश्च ८३२ । १५४ शेषाद्विभाषा ८९१ । १५५ न संज्ञायाम् ८९३ । १५६ ईयसश्च ८९४ । १५७ वन्दिते भ्रातुः ८९५ । १५८ ऋतश्छन्दसि

३५०८ । १५९ नाडीतन्त्र्योः स्वाङ्गे ८९६ । १६० निष्प्रवाणिश्च ८९७ ॥ ४ ॥ पादशतस्य तत्प्रकृतवृक्ज्येष्ठाभ्यां सपत्नान्ववतसात्खार्यां नञ्दुःसुभ्यो वयसि विंशतिः ॥

इति पञ्चमोऽध्यायः ।

षष्ठोऽध्यायः ।

प्रथमः पादः ।

१ एकाचो द्वे प्रथमस्य २१७५ । २ अजादेर्द्वितीयस्य २१७६ । ३ न न्द्राः संयोगादयः २४४६ । ४ पूर्वोऽभ्यासः २१७८ । ५ उभे अभ्यस्तम् ४२६ । ६ जक्षित्यादयः षट् ४२८ । ७ तुजादीनां दीर्घोऽभ्यासस्य ३५०९ । ८ लिटि धातोरनभ्यासस्य २१७७ । ९ सन्यङोः २३९५ । १० श्लौ २४९० । ११ चङि २३१५ । १२ दाश्वान्साह्वान्मीढ्वांश्च ३६२९ । १३ ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे १००३ । १४ बन्धुनि बहुव्रीहौ १००५ । १५ वचिस्वपियजादीनां किति २४०९ । १६ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च २४१२ । १७ लिट्यभ्यासस्योभयेषाम् २४०८ । १८ स्वापेश्चङि २५८४ । १९ स्वपिस्यमिव्येञां यङि २६४५ । २० न वशः २६४६ ॥ १ ॥ २१ चायः की २६४७ । २२ स्फायः स्फी निष्ठायाम् ३०४४ । २३ स्त्यः प्रपूर्वस्य ३०३३ । २४ द्रवमूर्तिस्पर्शयोः श्यः ३०२० । २५ प्रतेश्च ३०२१ । २६ विभाषाभ्यवपूर्वस्य ३०२२ । २७ शृतं पाके ३०६७ । २८ प्यायः पी ३०७२ । २९ लिड्यङोश्च २३२७ । ३० विभाषा श्वेः २४२० । ३१ णौ च संश्चङोः २६०१ । ३२ ह्वः संप्रसारणम् २५८६ । ३३ अभ्यस्तस्य च २४१७ । ३४ बहुलं छन्दसि ३५१० । ३५ चायः की ३५११ । ३६ अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताः श्रितमाशीराशीर्ताः ३५१२ । ३७ न संप्रसारणे संप्रसारणम् ३६३ । ३८ लिटि वयो यः २४१३ । ३९ वश्चास्यान्यतरस्यां किति २४१४ । ४० वेञः २४१५ ॥ २ ॥ ४१ ल्यपि च ३३३९ । ४२ ज्यश्च ३३४० । ४३ व्यश्च ३३४१ । ४४ विभाषा परेः ३३४२ । ४५ आदेच उपदेशेऽशिति २३७० । ४६ न व्यो लिटि २४१६ । ४७ स्फुरतिस्फुलत्योर्घञि ३१८५ । ४८ क्रीङ्जीनां णौ २६०० । ४९ सिध्यतेरपारलौकिके २६०२ । ५० मीनातिमिनोतिदीङां ल्यपि च २५०८ । ५१ विभाषा लीयतेः २५०९ । ५२ खिदेश्छन्दसि ३५१३ । ५३ अपगुरो णमुलि ३३७५ । ५४ चिस्फुरोर्णौ २५६९ । ५५ प्रजने वीयतेः २६०३ । ५६ बिभेतेर्हेतुभये २५९३ । ५७ नित्यं स्मयतेः २५९६ । ५८ सृजिदृशोर्झल्यमकिति २४०५ । ५९ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् २४०२ । ६० शीर्षंश्छन्दसि ३५१४ ॥ ३ ॥ ६१ ये च तद्धिते १६६७ । ६२ अचि शीर्षः १६६७ (वा ३४९२) । ६३ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु २२८ । ६४ धात्वादेः षः सः २२६४ । ६५ णो नः २२८६ । ६६ लोपो व्योर्वलि ८७३ । ६७ वेरपृक्तस्य ३७५ । ६८ हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् २५२ । ६९ एङ्ह्रस्वात्संबुद्धेः १९३ । ७० शेश्छन्दसि बहुलम् ३५१६ । ७१ ह्रस्वस्य पिति कृति तुक् २८५८ । ७२ संहितायाम् १४५ । ७३ छे च १४६ । ७४ आङ्माङोश्च १४७ । ७५ दीर्घात् १४८ । ७६ पदान्ताद्वा १४९ । ७७ इको यणचि ४७ । ७८ एचोऽयवायावः ६१ । ७९ वान्तो यि प्रत्यये ६३ । ८० धातोस्तन्निमित्तस्यैव ६४ ॥ ४ ॥

८१ क्षय्यजय्यौ शक्यार्थे ६५ । ८२ क्रय्यस्तदर्थे ६६ । ८३ भय्यप्रवय्ये च च्छन्दसि ३५१७ । ८४ एकः पूर्वपरयोः ६८ । ८५ अन्तादिवच्च ७५ । ८६ षत्वतुकोरसिद्ध ३१३२ । ८७ आद्गुणः ६९ । ८८ वृद्धिरेचि ७२ । ८९ एत्येधत्यूठ्सु ७३ । ९० आटश्च २६९ । ९१ उपसर्गादृति धातौ ७४ । ९२ वा सुप्यापिशलेः ७७ । ९३ औतोम्शसोः २८५ । ९४ एङि पररूपम् ७८ । ९५ ओमाङोश्च ८० । ९६ उस्यपदान्तात् २२१४ । ९७ अतो गुणे १९१ । ९८ अव्यक्तानुकरणस्यात इतौ ८१ । ९९ नाम्रेडितस्यान्त्यस्य तु वा ८२ । १०० नित्यमाम्रेडिते डाचि २१२८ (वा ३६३६) ॥ ५ ॥ १०१ अकः सवर्णे दीर्घः ८५ । १०२ । प्रथमयोः पूर्वसवर्णः १६४ । १०३ तस्माच्छसो नः पुंसि १९६ । १०४ नादिचि १६५ । १०५ दीर्घाज्जसि च २३९ । १०६ वा छन्दसि ३५१५ । १०७ अमि पूर्वः १९४ । १०८ संप्रसारणाच्च ३३० । १०९ एङः पदान्तादति ८६ । ११० ङसिङसोश्च २४६ । १११ ऋत उत् २७९ । ११२ ख्यत्यात्परस्य २५५ । ११३ अतो रोरप्लुतादप्लुते १६३ । ११४ हशि च १६६ । ११५ प्रकृत्यान्तःपादमव्यपरे ३५१८ । ११६ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ३५१९ । ११७ यजुष्युरः ३५२० । ११८ आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे ३५२१ । ११९ अङ्ग इत्यादौ च ३५२२ । १२० अनुदात्ते च कुधपरे ३५२३ ॥ ६ ॥ १२१ अवपथासि च ३५२४ । १२२ सर्वत्र विभाषा गोः ८७ । १२३ अवङ् स्फोटायनस्य ८८ । १२४ इन्द्रे च नित्यम् ८९ । १२५ प्लुतप्रगृह्या अचि ९० । १२६ आङोऽनुनासिकश्छन्दसि ३५२५ । १२७ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ९१ । १२८ ऋत्यकः ९२ । १२९ अप्लुतवदुपस्थिते ९८ । १३० ई३ चाक्रवर्मणस्य ९९ । १३१ दिव उत् ३३७ । १३२ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि १७६ । १३३ स्यश्छन्दसि बहुलम् ३५२६ । १३४ सोऽचि लोपे चेत्पादपूरणम् १७७ । १३५ सुट्कात्पूर्वः २५५३ । १३६ अडभ्यासव्यवायेऽपि २५३९ (वा ३६९८ ३६९९) । १३७ संपर्युपेभ्यः करोतौ भूषणे २५५० । १३८ समवाये च २५५१ । १३९ उपात्प्रतियत्न वैकृतवाक्याध्याहारेषु २५५२ । १४० किरतौ लवने २५३९ ॥ ७ ॥ १४१ हिंसायां प्रतेश्च २५४० । १४२ अपाच्चतुष्पाच्छकुनिष्वालेखने २६८८ । १४३ कुस्तुम्बुरूणि जातिः १०५८ । १४४ अपरस्पराः क्रियासातत्ये १०५९ । १४५ गोष्पदं सेवितासेवितप्रमाणेषु १०६० । १४६ आस्पदप्रतिष्ठायाम् १०६१ । १४७ आश्चर्यमनित्ये १०६२ । १४८ वर्चस्केऽवस्करः १०६३ । १४९ अपस्करो रथाङ्गम् १०६४ । १५० विष्किरः शकुनौ वा १०६५ । १५१ ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ३५२७ । १५२ प्रतिष्कशश्च कशेः १०६६ । १५३ प्रस्कण्वहरिश्चन्द्रावृषी १०६७ । १५४ मस्करमस्करिणौ वेणुपरिव्राजकयोः १०६८ । १५५ कास्तीराजस्तुन्दे नगरे १०६९ । १५६ कारस्करो वृक्षः १०७० (ग २०५) । १५७ पारस्करप्रभृतीनि च संज्ञायाम् १०७१ । १५८ अनुदात्तं पदमेकवर्जम् ३६५० । १५९ कर्षात्वतो घञोऽन्त उदात्तः ३६८० । १६० उञ्छादीनां च ३६८१ ॥ ८ ॥ १६१ अनुदात्तस्य च यत्रोदात्तलोपः ३६५१ । १६२ धातोः ३६७१ १६३ चितः ३७१० । १६४ तद्धितस्य ३७११ । १६५ कितः ३७१२ । १६६ तिसृभ्यो जसः ३७१३ । १६७ चतुरः शसि ३६८२ । १६८ सावेकाचस्तृतीयादिर्विभक्तिः ३७१४ । १६९ अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ३७१५ । १७० अञ्चेश्छन्दस्यसर्वनामस्थानम् ३७१६ । १७१ ऊडिदंपदाद्यप्पुम्रैद्युभ्यः ३७१७ । १७२ अष्टनो दीर्घात् ३७१८ । १७३ शतुर०

नुमो नयजादी ३७१९ । १७४ उदात्तयणो हल्पूर्वात् ३७२० । १७५ नाद्यात्वाः ३७२१ । १७६ ह्रस्वनुड्भ्यां मतुप् ३७२२ । १७७ नामन्यतरस्याम् ३७२३ । १७८ ङ्यश्छन्दसि बहुलम् ३७२४ । १७९ षट्त्रिचतुर्भ्यो हलादिः ३७२५ । १८० झल्युपोत्तमम् ३६८३ ॥ ९ ॥ १८१ विभाषा भाषायाम् ३६८४ । १८२ न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः ३७२६ । १८३ दिवो झल् ३७२७ । १८४ नृ चान्यतरस्याम् ३७२८ । १८५ तित्स्वरितम् ३७२९ । १८६ तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्ह्विङोः ३७३० । १८७ आदिः सिचोऽन्यतरस्याम् ३७३१ । १८८ स्वपादिर्हिंसामच्यनिटि ३६७२ । १८९ अभ्यस्तानामादिः ३६७३ । १९० अनुदात्ते च ६७४ । १९१ सर्वस्य सुपि ३६८५ । १९२ भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ३६७५ । १९३ लिति ३६७६ । १९४ आदिर्णमुल्यन्यतरस्याम् ३६७७ । १९५ अचः कर्तृयाकि ३६७८ । १९६ थलि च सेटीडन्तो वा ३७३२ । १९७ ञ्नित्यादिर्नित्यम् ३६८६ । १९८ आमन्त्रितस्य च ३६५३ । १९९ पथिमथोः सर्वनामस्थाने ३६८७ । २०० अन्तश्च तवै युगपत् ३६८८ ॥ १० ॥ २०१ क्षयो निवासे ३६८९ । २०२ जयकरणम् ३६९० २०३ वृषादीनां च ३६९१ । २०४ संज्ञायामुपमानम् ३६९२ । २०५ निष्ठा च द्व्यजनात् ३६९३ । २०६ शुष्कधृष्टौ ३६९४ । २०७ आशितः कर्ता ३६९५ । २०८ रिक्ते विभाषा ३६९६ । २०९ जुष्टार्पिते च च्छन्दसि ३६९७ । २१० नित्यं मन्त्रे ३६९८ । २११ युष्मदस्मदोर्ङसि ३६९९ । २१२ ङयि च ३७०० । २१३ यतोऽनावः ३७०१ । २१४ ईडवन्दवृशंसदुहां ण्यतः ३७०२ । २१५ विभाषावेण्विन्धानयोः ३७०३ । २१६ त्यागरागहासकुहश्वठक्रथानाम् ३७०४ । २१७ उपोत्तमं रिति ३७३३ । २१८ चङ्यन्यतरस्याम् ३६७९ । २१९ मतोः पूर्वमात्संज्ञायां स्त्रियाम् ३७०५ । २२० अन्तोऽवत्याः ३७०६ ॥ ११ ॥ २२१ ईवत्याः ३७०७ । २२२ चौ ३६५२ । २२३ समासस्य ३७३४ ॥ एकाचश्चायो ल्यपि च ये च क्षय्यजय्यावक्रः सवर्णेऽवपथाहिंसायामनुदात्तस्य विभाषा क्षय ईवत्यास्त्रीणि ॥

द्वितीयः पादः ।

१ बहुव्रीहौ प्रकृत्या पूर्वपदम् ३७३५ । २ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः ३७३६ । ३ वर्णो वर्णेष्वनेते ३७३७ । ४ गाधलवणयोः प्रमाणे ३७३८ । ५ दायाद्यं दायादे ३७३९ । ६ प्रतिबन्धि चिरकृच्छ्रयोः ३७४० । ७ पदेऽपदेशे ३७४१ । ८ निवाते वातत्राणे ३७४२ । ९ शारदेऽनार्तवे ३७४३ । १० अध्वर्युकषाययोर्जातौ ३७४४ । ११ सदृशप्रतिरूपयोः सादृश्ये ३७४५ । १२ द्विगौ प्रमाणे ३७४६ । १३ गन्तव्यपण्यं वाणिजे ३७४७ । १४ मात्रोपज्ञोपक्रमच्छाये नपुंसके ३७४८ । १५ सुखप्रिययोर्हिते ३७४९ । १६ प्रीतौ च ३७५० । १७ स्वं स्वामिनि ३७५१ । १८ पत्यावैश्वर्ये ३७५२ । १९ न भूवाक्चिद्दिधिषु ३७५३ । २० वा भुवनम् ३७५४ ॥ १ ॥ २१ आशङ्काबाधनेदीयःसंभावने ३७५५ । २२ पूर्वे भूतपूर्वे ३७५६ । २३ सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये ३७५७ । २४ विस्पष्टादीनि गुणवचनेषु ३७५८ । २५ श्रज्यावमकन्पापवत्सु भावे कर्मधारये ३७५९ । २६ कुमारश्च ३७६० । २७ आदिः प्रत्येनसि ३७६१ । २८ पूगेष्वन्यतरस्याम् ३७६४ । २९ इगन्तकालकपालभगालशरावेषु द्विगौ ३७६३ । ३० बह्वन्यतरस्याम् ३७६४ । ३१ दिष्टिवितस्त्योश्च ३७६५ । ३२ सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् ३७६६ । ३३ परिप्रत्युपापा वर्ज्यमानाहोरात्रावय-

वेषु ३७६७ । ३४ राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु ३७६८ । ३५ संख्या ३७६९ । ३६ आचार्यो-
पसर्जनश्चान्तेवासी ३७७० । ३७ कार्तकौजपादयश्च ३७७१ । ३८ महान्व्रीह्यपराह्णगृष्टीष्वासजाबा-
लभारभारतहैलिहिलरौरवप्रवृद्धेषु ३७७२ । ३९ क्षुल्लकश्च वैश्वदेवे ३७७३ । ४० उष्ट्रः सादिवाम्योः
३७७४ ॥ २ ॥ ४१ गौः सादसादिसारथिषु ३७७५ । ४२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्ली-
लदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ३७७६ । ४३ चतुर्थी तदर्थे
३७७७ । ४४ अर्थे ३७७८ । ४५ क्ते च ३७७९ । ४६ कर्मधारयेऽनिष्ठा ३७८० । ४७ अही-
ने द्वितीया ३७८१ । ४८ तृतीया कर्मणि ३७८२ । ४९ गतिरनन्तरः ३७८३ । ५० तादौ
च निति कृत्यतौ ३७८४ । ५१ तवै चान्तश्च युगपत् ३७८५ । ५२ अनिगन्तोऽञ्चतौ वप्रत्य-
ये ३७८६ । ५३ न्यधी च ३७८७ । ५४ ईषदन्यतरस्याम् ३७८८ । ५५ हिरण्यपरिमाणं धने
३७८९ । ५६ प्रथमोऽचिरोपसंपत्तौ ३७९० । ५७ कतरकतमौ कर्मधारये ३७९१ । ५८
आर्यो ब्राह्मणकुमारयोः ३७९२ । ५९ राजा च ३७९३ । ६० षष्ठी प्रत्येनसि ३७९४ ॥ ३ ॥
६१ क्ते नित्यार्थे ३७९५ । ६२ ग्रामः शिल्पिनि ३७९६ । ६३ राजा च प्रशंसायाम् ३७९७ ।
६४ आदिरुदात्तः ३७९८ । ६५ सप्तमीहारिणौ धर्म्येऽहरणे ३७९९ । ६६ युक्ते च ३८०० । ६७
विभाषाध्यक्षे ३८०१ । ६८ पापं च शिल्पिनि ३८०२ । ६९ गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे
३८०३ । ७० अङ्गानि मैरेये ३८०४ । ७१ भक्ताख्यास्तदर्थेषु ३८०५ । ७२ गोबिडालसिंहसैन्धवे-
षूपमाने ३८०६ । ७३ अके जीविकार्थे ३८०७ । ७४ प्राचां क्रीडायाम् ३८०८ । ७५ अणि
नियुक्ते ३८०९ । ७६ शिल्पिनि चाकृञः ३८१० । ७७ संज्ञायां च ३८११ । ७८ गोतन्ति-
यवं पाले ३८१२ । ७९ णिनि ३८१३ । ८० उपमानं शब्दार्थप्रकृतावेव ३८१४ ॥ ४ ॥ ८१
युक्तारोह्यादयश्च ३८१५ । ८२ दीर्घकाशतुषभ्राष्ट्रवटं जे ३८१६ । ८३ अन्त्यात्पूर्वं बह्वचः
३८१७ । ८४ ग्रामेऽनिवसन्तः ३८१८ । ८५ घोषादिषु च ३८१९ । ८६ छात्र्यादयः शालायाम् ३८२० ।
८७ प्रस्थेऽवृद्धमकर्क्यादीनाम् ३८२१ । ८८ मालादीनां च ३८२२ । ८९ अमहन्नवन्नगरे-
ऽनुदीचाम् ३८२३ । ९० अर्मे चावर्णं द्व्यच्त्र्यच् ३८२४ । ९१ न भूताधिकसंजीवमद्राश्मक-
ज्जलम् ३८२५ । ९२ अन्तः ३८२६ । ९३ सर्वं गुणकार्त्स्न्ये ३८२७ । ९४ संज्ञायां गिरिनि-
काययोः ३८२८ । ९५ कुमार्यां वयसि ३८२९ । ९६ उदकेऽकेवले ३८३० । ९७ द्विगौ क्रतौ
३८३१ । ९८ सभायां नपुंसके ३८३२ । ९९ पुरे प्राचाम् ३८३३ । १०० अरिष्टगौडपूर्वे च
३८३४ ॥ ५ ॥ १०१ न हास्तिनफलकमार्देयाः ३८३५ । १०२ कुसूलकूपकुम्भशालं बिले
३८३६ । १०३ दिक्छब्दा ग्रामजनपदाख्यानचानराटेषु ३८३७ । १०४ आचार्योपसर्जन-
श्चान्तेवासिनि ३८३८ । १०५ उत्तरपदवृद्धौ सर्वं च ३८३९ । १०६ बहुव्रीहौ विश्वं संज्ञायाम्
३८४० । १०७ उदराश्वेषुषु ३८४१ । १०८ क्षेपे ३८४२ । १०९ नदी बन्धुनि ३८४३ ।
११० निष्ठोपसर्गपूर्वमन्यतरस्याम् ३८४४ । १११ उत्तरपदादिः ३८४५ । ११२ कर्णो वर्णल-
क्षणात् ३८४६ । ११३ संज्ञौपम्ययोश्च ३८४७ । ११४ कण्ठपृष्ठग्रीवाजङ्घं च ३८४८ । ११५
शृङ्गमवस्थायां च ३८४९ । ११६ नञो जरमरमित्रमृताः ३८५० । ११७ सोर्मनसी अलोमो-
षसी ३८५१ । ११८ क्रत्वादयश्च ३८५२ । ११९ आद्युदात्तं द्व्यच्छन्दसि ३८५३ । १२० वी-
रवीर्यौ च ३८५४ ॥ ६ ॥ १२१ कूलतीरतूलमूलशालाक्षसममव्ययीभावे ३८५५ ।
१२२ कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ३८५६ । १२३ तत्पुरुषे शालायां नपुंसके

३८५७ । १२४ कन्था च ३८५८ । १२५ आदिश्चिहणादीनाम् ३८५९ । १२६ चेलखेटकटुककाण्डं गर्हायाम् ३८६० । १२७ चीरमुपमानम् ३८६१ । १२८ पललसूपशाकं मिश्रे ३८६२ । १२९ कूलसूदस्थलकर्षाः संज्ञायाम् ३८६३ । १३० अकर्मधारये राज्यम् ३८६४ । १३१ वर्ग्यादयश्च ३८६५ । १३२ पुत्रः पुम्भ्यः ३८६६ । १३३ नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ३८६७ । १३४ चूर्णादीन्यप्राणिषष्ठ्याः ३८६८ । १३५ षट् च काण्डादीनि ३८६९ । १३६ कुण्डं वनम् ३८७० । १३७ प्रकृत्या भगालम् ३८७१ । १३८ शितेर्नित्याबह्वज्बहुव्रीहावभसत् ३८७२ । १३९ गतिकारकोपपदात्कृत् ३८७३ । १४० उभे वनस्पत्यादिषु युगपत् ३८७४ ॥ ७ ॥ १४१ देवताद्वन्द्वे च ३८७५ । १४२ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ३८७६ । १४३ अन्तः ३८७७ । १४४ थाथघञ्क्ताजबित्रकाणाम् ३८७८ । १४५ सूपमानात्क्तः ३८७९ । १४६ संज्ञायामनाचितादीनाम् ३८८० । १४७ प्रवृद्धादीनां च ३८८१ । १४८ कारकाद्दत्तश्रुतयोरेवाशिषि ३८८२ । १४९ इत्थंभूतेन कृतमिति च ३८८३ । १५० अनो भावकर्मवचनः ३८८४ । १५१ मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ३८८५ । १५२ सप्तम्याः पुण्यम् ३८८६ । १५३ ऊनार्थकलहं तृतीयायाः ३८८७ । १५४ मिश्रं चानुपसर्गमसंधौ ३८८८ । १५५ नञो गुणप्रतिषेधे संपाद्यर्हहितालमर्थास्ताद्धिताः ३८८९ । १५६ ययतोश्चातदर्थे ३८९० । १५७ अच्कावशक्तौ ३८९१ । १५८ आक्रोशे च ३८९२ । १५९ संज्ञायाम् ३८९३ । १६० कृत्योकेष्णुच्चार्वादयश्च ३८९४ ॥ ८ ॥ १६१ विभाषा तृन्नन्नतीक्ष्णशुचिषु ३८९५ । १६२ बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने ३८९६ । १६३ संख्यायाः स्तनः ३८९७ । १६४ विभाषा छन्दसि ३८९८ । १६५ संज्ञायां मित्राजिनयोः ३८९९ । १६६ व्यवायिनोऽन्तरम् ३९०० । १६७ मुखं स्वाङ्गम् ३९०१ । १६८ नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ३९०२ । १६९ निष्ठोपमानादन्यतरस्याम् ३९०३ । १७० जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमितप्रतिपन्नाः ३९०४ । १७१ वा जाते ३९०५ । १७२ नञ्सुभ्याम् ३९०६ । १७३ कपि पूर्वम् ३९०७ । १७४ ह्रस्वान्तेऽन्त्यात्पूर्वम् ३९०८ । १७५ बहोर्नञ्वदुत्तरपदभूम्नि ३९०९ । १७६ न गुणादयोऽवयवाः ३९१० । १७७ उपसर्गात्स्वाङ्गं ध्रुवमपर्शु ३९११ । १७८ वनं समासे ३९१२ । १७९ अन्तः ३९१३ । १८० अन्तश्च ३९१४ ॥ ९ ॥ १८१ न निविभ्याम् ३९१५ । १८२ परेरभितोभावि मण्डलम् ३९१६ । १८३ प्रादस्वाङ्गं संज्ञायाम् ३९१७ । १८४ निरुदकादीनि च ३९१८ । १८५ अभेर्मुखम् ३९१९ । १८६ अपाच्च ३९२० । १८७ स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम च ३९२१ । १८८ अधेरुपरिस्थम् ३९२२ । १८९ अनोरप्रधानकनीयसी ३९२३ । १९० पुरुषश्चान्वादिष्टः ३९२४ । १९१ अतेरकृत्पदे ३९२५ । १९२ नेरनिधाने ३९२६ । १९३ प्रतेरंश्वादयस्तत्पुरुषे ३९२७ । १९४ उपाद् द्व्यजजिनमगौरादयः ३९२८ । १९५ सोरवक्षेपणे ३९२९ । १९६ विभाषोत्पुच्छे ३९३० । १९७ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ३९३१ । १९८ सक्थं चाक्रान्तात् ३९३२ । १९९ परादिश्छन्दसि बहुलम् ३९३३ ॥ बहुव्रीहावाशङ्कागौः सादक्के नित्यार्थे युक्तान हास्तिनकूलतीरदेवताविभाषा न निष्ठ्येकोनविंशतिः ॥

तृतीयः पादः ।

१ अलुगुत्तरपदे ९५८ । २ पञ्चम्याः स्तोकादिभ्यः ९५९ । ३ ओजःसहोऽम्भस्तमस्तृतीयायाः ९६० । ४ मनसः संज्ञायाम् ९६१ । ५ आज्ञायिनि च ९६२ । ६ आत्मनश्च पूरणे ९६३ । ७ वैयाकरणाख्यायां चतुर्थ्याः ९६४ । ८ परस्य च ९६५ । ९ हलदन्तात्सप्तम्याः संज्ञायाम् ९६६ । १० कारनाम्नि च प्राचां हलादौ ९६८ । ११ मध्याद्गुरौ ९६९ । १२ अमूर्धमस्तकात्स्वाङ्गादकामे ९७० । १३ बन्धे च विभाषा ९७१ । १४ तत्पुरुषे कृति बहुलम् ९७२ । १५ प्रावृट्शरत्कालदिवां जे ९७३ । १६ विभाषा वर्षक्षरशरवरात् ९७४ । १७ घकालतनेषु कालनाम्नः ९७५ । १८ शयवासवासिष्वकालात् ९७६ । १९ नेन्सिद्धबध्नातिषु च ९७७ । २० स्थे च भाषायाम् ९७८ ॥ १ ॥ २१ षष्ठ्या आक्रोशे ९७९ । २२ पुत्रेऽन्यतरस्याम् ९८० । २३ ऋतो विद्यायोनिसंबन्धेभ्यः ९८१ । २४ विभाषा स्वसृपत्योः ९८२ । २५ आनङृतो द्वन्द्वे ९२१ । २६ देवताद्वन्द्वे च ९२२ । २७ ईदग्नेः सोमवरुणयोः ९२३ । २८ इद्वृद्धौ ९२५ । २९ दिवो द्यावा ९२६ । ३० दिवसश्च पृथिव्याम् ९२७ । ३१ उषासोषसः ९२८ । ३२ मातरपितरावुदीचाम् ९२९ । ३३ पितरामातरा च च्छन्दसि ३५२८ । ३४ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ८३१ । ३५ तसिलादिष्वा कृत्वसुचः ८३६ । ३६ क्यङ्मानिनोश्च ८३७ । ३७ न कोपधायाः ८३८ । ३८ संज्ञापूरण्योश्च ८३९ । ३९ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ८४० । ४० स्वाङ्गाच्चेतोऽमानिनि ८४१ ॥ २ ॥ ४१ जातेश्च ८४२ । ४२ पुंवत्कर्मधारयजातीयदेशीयेषु ७४६ । ४३ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ९८५ । ४४ नद्याः शेषस्यान्यतरस्याम् ९८६ । ४५ उगितश्च ९८७ । ४६ आन्महतः समानाधिकरणजातीययोः ८०७ । ४७ द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ८०८ । ४८ त्रेस्त्रयः ८०९ । ४९ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ८१० । ५० हृदयस्य हृल्लेखयदण्लासेषु ९८८ । ५१ वा शोकष्यञ्रोगेषु ९८९ । ५२ पादस्य पदाज्यातिगोपहतेषु ९९० । ५३ पद्यत्यतदर्थे ९९१ । ५४ हिमकाषिहतिषु च ९९२ । ५५ ऋचः शे ९९३ । ५६ वा घोषमिश्रशब्देषु ९९४ । ५७ उदकस्योदः संज्ञायाम् ९९५ । ५८ पेषंवासवाहनधिषु च ९९६ । ५९ एकहलादौ पूरयितव्येऽन्यतरस्याम् ९९७ । ६० मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ९९८ ॥ ३ ॥ ६१ इको ह्रस्वोऽङ्यो गालवस्य ९९९ । ६२ एक तद्धिते च १००० । ६३ ङ्यापोः संज्ञाछन्दसोर्बहुलम् १००१ । ६४ त्वे च १००२ । ६५ इष्टकेषीकामालानां चिततूलभारिषु १००६ । ६६ खित्यनव्ययस्य २९४३ । ६७ अरुर्द्विषदजन्तस्य मुम् २९४२ । ६८ इच एकाचोऽम्प्रत्ययवच्च २९९४ । ६९ वाचंयमपुरंदरौ च २९५७ । ७० कारे सत्यागदस्य १००७ । ७१ श्येनतिलस्य पाते ञे १२६८ । ७२ रात्रेः कृति विभाषा १००८ । ७३ नलोपो नञः ७५७ । ७४ तस्मान्नुडचि ७५८ । ७५ नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या, ७५९ । ७६ एकादिश्चैकस्य चादुक् ८११ । ७७ नगोऽप्राणिष्वन्यतरस्याम् ७६० । ७८ सहस्य सः संज्ञायाम् १००९ । ७९ ग्रन्थान्ताधिके च १०१० । ८० द्वितीये चानुपाख्ये १०११ ॥ ४ ॥ ८१ अव्ययीभावे चाकाले ६६० । ८२ वोपसर्जनस्य ८४९ । ८३ प्रकृत्याशिष्यगोवत्सहलेषु ८५० । ८४ समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु १०१२ । ८५ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु

१०१३ । ८६ चरणे ब्रह्मचारिणि १०१४ । ८७ तीर्थे ये १०१५ । ८८ विभाषोदरे १०१६। ८९ दृग्दृशवतुषु १०१७ । ९० इदंकिमोरीश्की १०१८ । ९१ आ सर्वनाम्नः ४३० । ९२ विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये ४१८ । ९३ समः समि ४२१ । ९४ तिरसस्तिर्यलोपे ४२३। ९५ सहस्य सध्रिः ४२२ । ९६ सध मादस्थयोश्छन्दसि ३५२९ । ९७ द्व्यन्तरुपसर्गेभ्योऽप ईत् ९४१ । ९८ ऊदनोर्देशे ९४२ । ९९ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु १०२५ । १०० अर्थे विभाषा १०२६॥ ५॥ १०१ कोः कत्तत्पुरुषेऽचि १०२७ । १०२ रथवदयोश्च १०२८ । १०३ तृणे च जातौ १०२९ । १०४ का पथ्यक्षयोः १०३० । १०५ ईषदर्थे १०३१ । १०६ विभाषा पुरुषे १०३२ । १०७ कवं चोष्णे १०३३ । १०८ पथि च च्छन्दसि ३५३० । १०९ पृषोदरादीनि यथोपदिष्टम् १०३४ । ११० संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ २३८ । १११ ढ्रलोपे पूर्वस्य दीर्घोऽणः १७४ । ११२ सहिवहोरोदवर्णस्य २३५७ । ११३ साढ्यै साढ्वा साढेति निगमे ३५३१ । ११४ संहितायाम् १०३५ । ११५ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य १०३६। ११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ १०३७ । ११७ वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् १०३८ । ११८ वले १०४० । ११९ मतौ बह्वचोऽनजिरादीनाम् १०४१ । १२० शरादीनां च १०४२ ॥ ६॥ १२१ इको वहेऽपीलोः १०४३ । १२२ उपसर्गस्य घञ्यमनुष्ये वहुलम् १०४४ । १२३ इकः काशे १०४५ । १२४ दस्ति ३०७९ । १२५ अष्टनः संज्ञायाम् १०४६ । १२६ छन्दसि च ३५३२ । १२७ चितेः कपि १०४७ । १२८ विश्वस्य वसुराटोः ३७९ । १२९ नरे संज्ञायाम् १०४८ । १३० मित्रे चर्षौ १०४९ । १३१ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ३५३३ । १३२ ओषधेश्च विभक्तावप्रथमायाम् ३५३४ । १३३ ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ३५३५ । १३४ इकः सुञि ३५३६ । १३५ द्व्यचोऽतस्तिङः ३५३७। १३६ निपातस्य च ३५३८ । १३७ अन्येषामपि दृश्यते ३५३९ । १३८ चौ ४१७ । १३९ संप्रसारणस्य १००४ । अलुक्षष्ठ्या जातेरिकोऽव्ययीभावे कोः कत्तदिको वहे एकोनविंशतिः॥

चतुर्थः पादः।

१ अङ्गस्य २०० । २ हलः २५५९ । ३ नामि २०९ । ४ न तिसृचतसृ ३०० । ५ छन्दस्युभयथा ३५४० । ६ नृ च २८३ । ७ नोपधायाः ३७० । ८ सर्वनामस्थाने चासंबुद्धौ २५०। ९ वा षपूर्वस्य निगमे ३५४१ । १० सान्तमहतः संयोगस्य ३१७ । ११ अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तृणाम् २७७ । १२ इन्हन्पूषार्यम्णां शौ ३५६ । १३ सौ च ३५७। १४ अत्वसन्तस्य चाधातोः ४२५ । १५ अनुनासिकस्य क्विझलोः क्ङिति २६६६ । १६ अज्झनगमां सनि २६१४ । १७ तनोतेर्विभाषा २६२२ । १८ क्रमश्च क्त्वि ३३२९ । १९ च्छ्वोः शूडनुनासिके च २५६१ । २० ज्वरत्वरस्रिव्यविमवामुपधायाश्च २६५४ ॥ १ ॥ २१ राल्लोपः २६५५ । २२ असिद्धवदत्राभात् २१८३ । २३ श्नान्नलोपः २५४४ । २४ अनिदितां हल उपधायाः क्ङिति ४१५ । २५ दंशसञ्जस्वञ्जां शपि २३९६ । २६ रञ्जेश्च २३९७ । २७ घञि च भावकरणयोः ३१८९ । २८ स्यदो जवे ३१८६ । २९ अवोदैधौद्मप्रश्रथहिमश्रथाः ३१८०। ३० नाञ्चेः पूजायाम् ४२४ । ३१ क्त्वि स्कन्दिस्यन्दोः ३३२१ । ३२ जान्तनशां विभाषा ३३३० । ३३ भञ्जेश्च चिणि २७६४ । ३४ शास इदङ्हलोः २४८६ । ३५ शा हौ २४८७।

३६ हन्तेर्जः २४३१ । ३७ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति
२४२८ । ३८ वा ल्यपि ३३३४ । ३९ न क्तिचि दीर्घश्च ३३१४ । ४० गमः क्वौ २९८६ ।
॥ २ ॥ ४१ विड्वनोरनुनासिकस्यात् २९८२ । ४२ जनसनखनां सञ्झलोः २५०४ । ४३
ये विभाषा २३१९ । ४४ तनोतेर्यकि २७५९ । ४५ सनः क्तिचि लोपश्चास्यान्यतरस्याम् ३३१९ ।
४६ आर्धधातुके २३०७ । ४७ भ्रस्जो रोपधयो रमन्यतरस्याम् २५३५ । ४८ अतो
लोपः २३०८ । ४९ यस्य हलः २६३१ । ५० क्यस्य विभाषा २६६० । ५१ णेरनिटि २३१३
५२ निष्ठायां सेटि ३०५७ । ५३ जनिता मन्त्रे ३५४२ । ५४ शमिता यज्ञे ३५४३ । ५५ अ
यामन्ताल्वाय्येत्न्विष्णुषु २३११ । ५६ ल्यपि लघुपूर्वात् ३३३६ । ५७ विभाषापः ३३३७ । ५८
युप्लुवोर्दीर्घश्छन्दसि ३५४४ । ५९ क्षियः ३३३८ । ६० निष्ठायामण्यदर्थे ३०१४ ॥ ३ ॥ ६१
वाक्रोशदैन्ययोः ३०८१ । ६२ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चि-
ण्वदिट् च २७५७ । ६३ दीङो युडचि क्ङिति २५०७ । ६४ आतो लोप इटि च २३७२ । ६५
ईद्यति २८४३ । ६६ घुमास्थागापाजहातिसां हलि २४६२ । ६७ एर्लिङि २३७४ । ६८ वा-
न्यस्य संयोगादेः २३७८ । ६९ न ल्यपि ३३३५ । ७० मयतेरिदन्यतरस्याम् ३३१८ । ७१
लुङ्लङ्लृङ्क्ष्वडुदात्तः २२०६ । ७२ आडजादीनाम् २२५४ । ७३ छन्दस्यपि दृश्यते ३५४५ ।
७४ न माङ्योगे २२२८ । ७५ बहुलं छन्दस्यमाङ्योगेऽपि ३५४६ । ७६ इरयो रे ३५४७ ।
७७ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ २७१ । ७८ अभ्यासस्यासवर्णे २२९० । ७९ स्त्रियाः
३०१ । ८० वाम्शसोः ३०२ ॥ ४ ॥ ८१ इणो यण् २४५५ । ८२ एरनेकाचोऽसंयोगपूर्वस्य
२७२ । ८३ ओः सुपि २८१ । ८४ वर्षाभ्वश्च २८२ । ८५ न भूसुधियोः २७३ । ८६ छन्द-
स्युभयथा ३५४८ । ८७ हुश्नुवोः सार्वधातुके २३८७ । ८८ भुवो वुग्लुङ्लिटोः २१७४ ।
८९ ऊदुपधाया गोहः २३६४ । ९० दोषो णौ २६०४ । ९१ वा चित्तविरागे २६०५ । ९२ मितां
ह्रस्वः २५६८ । ९३ चिण्णमुलोर्दीर्घोऽन्यतरस्याम् २७६२ । ९४ खचि ह्रस्वः २९५५ । ९५
ह्लादो निष्ठायाम् ३०७३ । ९६ छादेर्घेऽद्व्युपसर्गस्य ३२९७ । ९७ इस्मन्त्रन्क्विषु च २९८५ ।
९८ गमहनजनखनघसां लोपः क्ङित्यनङि २३६३ । ९९ तनिपत्योश्छन्दसि ३५४९ । १००
घसिभसोर्हलि च ३५५० ॥ ५ । १०१ हुझल्भ्यो हेर्धिः २४२५ । १०२श्रुशृणुपॄकृवृभ्यश्छन्दसि
३५५१ । १०३ अङितश्च ३५५२ । १०४ चिणो लुक् २३२९ । १०५ अतो हेः २२०२ ।
१०६ उतश्च प्रत्ययादसंयोगपूर्वात् २३३४ । १०७ लोपश्चास्यान्यतरस्यां म्वोः २३३२ । १०८
नित्यं करोतेः २५४८ । १०९ ये च २५४९ । ११० अत उत्सार्वधातुके २४६७ । १११
श्नसोरल्लोपः २४६९ । ११२ श्नाभ्यस्तयोरातः २४८३ । ११३ ई हल्यघोः २४९७ । ११४
इद्दरिद्रस्य २४८२ । ११५ भियोऽन्यतरस्याम् २४९२ । ११६ जहातेश्च २४९८ । ११७ आ
च हौ २४९९ । ११८ लोपो यि २५०० । ११९ घ्वसोरेद्धावभ्यासलोपश्च २४७१ । १२०
अत एकहल्मध्येऽनादेशादेर्लिटि २२६० ॥ ६ ॥ १२१ थलि च सेटि २२६१ । १२२ तॄफ-
लभजत्रपश्च २३०१ । १२३ राधो हिंसायाम् २५३२ । १२४ वा जॄभ्रमुत्रसाम् २३५६ । १२५
फणां च सप्तानाम् २३५४ । १२६ न शसददवादिगुणानाम् २२६३ । १२७ अर्वणस्त्रसावनञः
३६४ । १२८ मघवा बहुलम् ३६० । १२९ भस्य ३३३ । १३० पादः पत् ४१४ । १३१
वसोः संप्रसारणम् ४३५ । १३२ वाह ऊठ् ३२९ । १३३ श्वयुवमघोनामतद्धिते ३६२ । १३४

अल्लोपोऽनः २३४ । १३५ षपूर्वहन्धृतराज्ञामणि ११६० । १३६ विभाषा ङिश्योः २३७ । १३७ न संयोगाद्वमन्तात् ३९९ । १३८ अचः ४१६ । १३९ उद ईत् ४२० । १४० आतो धातोः २४० ॥ ७ ॥ १४१ मन्त्रेष्वाङ्यादेरात्मनः ३५५४ । १४२ ति विंशतेर्डिति ८४४ । १४३ टेः ३१६ । १४४ नस्तद्धिते ६७९ । १४५ अह्नष्टखोरेव ७८९ । १४६ ओर्गुणः ८४७ । १४७ ढे लोपोऽकद्र्वाः ११४२ । १४८ यस्येति च ३११ । १४९ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ४९९ । १५० हलस्तद्धितस्य ४७२ । १५१ आपत्यस्य च तद्धितेऽनाति १०८२ । १५२ क्यच्व्योश्च ३११९ । १५३ बिल्वकादिभ्यश्छस्य लुक् १३११ । १५४ तुरिष्ठेमेयःसु २००८ । १५५ टेः १७८६ । १५६ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः २०१५ । १५७ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः २०१६ । १५८ बहोर्लोपो भू च बहोः २०१७ । १५९ इष्ठस्य यिट् च २०१८ । १६० ज्यादादीयसः २०१२ ॥ ८ ॥ १६१ र ऋतो हलादेर्लघोः १७८५ । १६२ विभाषर्जोश्छन्दसि ३५५५ । १६३ प्रकृत्यैकाच् २०१० । १६४ इनण्यनपत्ये १२४५ । १६५ गाथिविदथिकेशिगणिपणिनश्च १२७५ । १६६ संयोगादिश्च ११५६ । १६७ अन् ११५५ । १६८ ये चाभावकर्मणोः ११५४ । १६९ आत्माध्वानौ खे १६७१ । १७० न मपूर्वोऽपत्येऽवर्मणः ११५७ । १७१ ब्राह्मोऽजातौ ११५८ । १७२ कार्मस्ताच्छील्ये १६१३ । १७३ औक्षमनपत्ये ११५९ । १७४ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ११४५ । १७५ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ३५५६ ॥ अङ्गस्य राल्लोपो विड्वनोर्वाक्रोशेणो यण्हुझल्म्यस्थालि च मन्त्रेषु र ऋतः पञ्चदश ॥

इति षष्ठोऽध्यायः ।

सप्तमोऽध्यायः ।

प्रथमः पादः ।

१ युवोरनाकौ १२४७ । २ आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ४७५ । ३ झोऽन्तः २१६९ । ४ अदभ्यस्तात् २४७९ । ५ आत्मनेपदेष्वनतः २२५८ । ६ शीङो रुट् २४४२ । ७ वेत्तेर्विभाषा २७०१ । ८ बहुलं छन्दसि ३५५७ । ९ अतो भिस ऐस् २०३ । १० बहुलं छन्दसि ३५५८ । ११ नेदमदसोरकोः ३४९ । १२ टाङसिङसामिनात्स्याः २०१ । १३ ङेर्यः २०४ । १४ सर्वनाम्नः स्मै २१५ । १५ ङसिङ्योः स्मात्स्मिनौ २१६ । १६ पूर्वादिभ्यो नवभ्यो वा २२१ । १७ जसः शी २१४ । १८ औङ आपः २८७ । १९ नपुंसकाच्च ३१० । २० जश्शसोः शिः ३१२ ॥ १ ॥ २१ अष्टाभ्य औश् ३७२ । २२ षड्भ्यो लुक् ३६१ । २३ स्वमोर्नपुंसकात् ३१९ । २४ अतोऽम् ३०९ । २५ अद्ड्डतरादिभ्यः पञ्चभ्यः ३१५ । २६ नेतराच्छन्दसि ३५५९ । २७ युष्मदस्मद्भ्यां ङसोऽश् ३९९ । २८ ङेप्रथमयोरम् ३८२ । २९ शसो न ३९१ । ३० भ्यसो भ्यम् ३९५ । ३१ पञ्चम्या अत् ३९७ । ३२ एकवचनस्य च ३९६ । ३३ साम आकम् ४०० । ३४ आत औ णलः २३७१ । ३५ तुह्योस्तातङाशिष्यन्यतरस्याम् २१९७ । ३६ विदेः शतुर्वसुः ३१०५ । ३७ समासेऽनञ्पूर्वे क्त्वो ल्यप् ३३३२ । ३८ क्त्वापि च्छन्दसि ३५६० । ३९ सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ३५६१ । ४०

अमो मश् ३५६२ ॥ २ ॥ ४१ लोपस्त आत्मनेपदेषु ३५६३। ४२ ध्वमो ध्वात् ३५६४। ४३ यजध्वैनमिति च ३५६५। ४४ तस्य तात् ३५६६। ४५ तप्तनप्तनथनाश्च ३५६७। ४६ इदन्तो मसि ३५६८। ४७ क्त्वो यक् ३५६९। ४८ इष्ट्वीनमिति च ३५७०। ४९ स्नात्व्यादयश्च ३५७१। ५० आज्जसेरसुक् ३५७२। ५१ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि २६६२। ५२ आमि सर्वनाम्नः सुट् २१७। ५३ त्रेस्त्रयः २६४। ५४ ह्रस्वनद्यापो नुट् २०८। ५५ षट्चतुर्भ्यश्च ३२८। ५६ श्रीग्रामण्योश्छन्दसि ३५७३। ५७ गोः पादान्ते ३५७४। ५८ इदितो नुम्धातोः २२६२। ५९ शे मुचादीनाम् २५४२। ६० मस्जिनशोर्झलि २५१७॥ ३ ॥ ६१ रधिजभोरचि २३०२। ६२ नेट्यलिटि रधेः २५१६। ६३ रभेरशब्लिटोः २५८१। ६४ लभेश्च २५८२। ६५ आङो यि २८४५। ६६ उपात्प्रशंसायाम् २८४६। ६७ उपसर्गात्खल्घञोः ३३०६। ६८ न सुदुर्भ्यां केवलाभ्याम् ३३०७। ६९ विभाषा चिण्णमुलोः २७६५। ७० उगिदचां सर्वनामस्थानेऽधातोः ३६१। ७१ युजेरसमासे ३७६। ७२ नपुंसकस्य झलचः ३१४। ७३ इकोऽचि विभक्तौ ३२०। ७४ तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ३२१। ७५ अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ३२२। ७६ छन्दस्यपि दृश्यते ३५७५। ७७ ई च द्विवचने ३५७६। ७८ नाभ्यस्ताच्छतुः ४२७। ७९ वा नपुंसकस्य ४४४। ८० आच्छीनद्योर्नुम् ४४५। ॥ ४ ॥ ८१ शप्श्यनोर्नित्यम् ४४६। ८२ सावनडुहः ३३२। ८३ दृक्स्ववःस्वतवसां छन्दसि ३५७७। ८४ दिव औत् ३३६। ८५ पथिमथ्यृभुक्षामात् ३६५। ८६ इतोऽत्सर्वनामस्थाने ३६६। ८७ थो न्थः ३६७। ८८ भस्य टेर्लोपः ३६८। ८९ पुंसोऽसुङ् ४३६। ९० गोतो णित् २८४। ९१ णलुत्तमो वा २२८३। ९२ सख्युरसंबुद्धौ २५३। ९३ अनङ् सौ २४८। ९४ ऋदुशनस्पुरुदंसोऽनेहसां च २७६। ९५ तृज्वत्क्रोष्टुः २७४। ९६ स्त्रियां च ३०५। ९७ विभाषा तृतीयादिष्वचि २७८। ९८ चतुरनडुहोरामुदात्तः ३३१। ९९ अम्संबुद्धौ ३३३। १०० ऋत इद्धातोः २३९०॥ ५ ॥ १०१ उपधायाश्च २५७१। १०२ उदोष्ठ्यपूर्वस्य २४९४। १०३ बहुलं छन्दसि ३५७८॥ युवोरष्टाभ्यो लोपो राधिशप्श्यनोरुपधायास्त्रीणि ॥

द्वितीयः पादः।

१ सिचि वृद्धिः परस्मैपदेषु २२९७। २ अतो ल्रान्तस्य २३३०। ३ वदव्रजहलन्तस्याचः २२६७। ४ नेटि २२६८। ५ ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् २२९९। ६ ऊर्णोतेर्विभाषा २४४९। ७ अतो हलादेर्लघोः २२८४। ८ नेड्वशि कृति २९८१। ९ तितुत्रतथसिसुसरकसेषु च ३१६३। १० एकाच उपदेशेऽनुदात्तात् २२४६। ११ श्र्युकः किति २३८१। १२ सनि ग्रहगुहोश्च २६१०। १३ कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि २२९३। १४ श्वीदितो निष्ठायाम् ३०३९। १५ यस्य विभाषा ३०२५। १६ आदितश्च ३०३६। १७ विभाषा भावादिकर्मणोः ३०५४। १८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ३०५८। १९ धृषिशसी वैयात्ये ३०५९। २० दृढः स्थूलबलयोः ३०६०॥ १ ॥ २१ प्रभौ परिवृढः ३०६१। २२ कृच्छ्रगहनयोः कषः ३०६२। २३ घुषिरविशब्दने ३०६३। २४ अर्देः संनिविभ्यः ३०६४। २५ अभेश्चाविदूर्ये ३०६५। २६ णेरध्ययने वृत्तम् ३०६६। २७ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ३०६८। २८ रुष्यमत्वरसंघुषास्वनाम् ३०६९। २९ हृषेर्लोम-

सु ३०७० । ३० अपचितश्च ३०७१ । ३१ हु ह्वरेश्छन्दसि ३५७९ । ३२ अपरिह्वृताश्च ३५८० । ३३ सोमे ह्वरितः ३५८१ । ३४ प्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च ३५८२ । ३५ आर्धधातुकस्येड्वलादेः २१८४ । ३६ स्नुक्रमोरनात्मनेपदनिमित्ते २३२३ । ३७ ग्रहोऽलिटि दीर्घः २५६२ । ३८ वृतो वा २३९१ । ३९ न लिङि २५२९ । ४० सिचि च परस्मैपदेषु २३९२ ॥२॥ ४१ इट् सनि वा २६२५ । ४२ लिङ्सिचोरात्मनेपदेषु २५२८ ।४३ ऋतश्च संयोगादेः २५२६ । ४४ स्वरतिसूतिसूयतिधूञूदितो वा २२७९ । ४५ रधादिभ्यश्च २५१५ । ४६ निरः कुषः २५६० । ४७ इण्निष्ठायाम् ३०४५ । ४८ तीषसहलुभरुषरिषः २३४० । ४९ सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् २६१८ । ५० क्लिशः क्त्वानिष्ठयोः ३०४९ । ५१ पूङश्च ३०५० । ५२ वसतिक्षुधोरिट् ३०४६ । ५३ अञ्चेः पूजायाम् ३०४७ । ५४ लुभो विमोहने ३०४८ । ५५ जृव्रश्च्योः क्त्वि ३३२७ । ५६ उदितो वा ३३२८ । ५७ सेऽसिचि कृतचृतच्छृदतृदनृतः २५०६ । ५८ गमेरिट् परस्मैपदेषु २४०१ । ५९ न वृद्भ्यश्चतुर्भ्यः २३४८ । ६० तासि च क्लृपः २३५२ ॥ ३ ॥ ६१ अचस्तास्वत्थल्यनिटो नित्यम् २२९४ । ६२ उपदेशेऽत्वतः २२९५ । ६३ ऋतो भारद्वाजस्य २२९६ । ६४ बभूथाततन्थजगृभ्मववर्थेति निगमे ३५२७ । ६५ विभाषा सृजिदृशोः २४०४ । ६६ इडत्त्यर्तिव्ययतीनाम् २३८४ । ६७ वस्वेकाजाद्घसाम् ३०९६ । ६८ विभाषा गमहनविदविशाम् ३०९९ । ६९ सनिंससनिवांसम् ३५८३ । ७० ऋद्धनोः स्ये २३६६ । ७१ अञ्जेः सिचि २५४६ । ७२ स्तुसुधूञ्भ्यः परस्मैपदेषु २३८५ । ७३ यमरमनमातां सक्च २३७७ । ७४ स्मिपूङ्रञ्ज्वशां सनि २६२६ । ७५ किरश्च पञ्चभ्यः २६११ । ७६ रुदादिभ्यः सार्वधातुके २४७४ । ७७ ईशः से २४३९ । ७८ ईडजनोर्ध्वे च २४४० । ७९ लिङः सलोपोऽनन्त्यस्य २२११ । ८० अतो येयः २२१२ ॥ ४ ॥ ८१ आतो ङितः २२३९ । ८२ आने मुक् ३१०१ । ८३ ईदासः ३१०४ । ८४ अष्टन आ विभक्तौ ३७१ । ८५ रायो हलि २८६ । ८६ युष्मदस्मदोरनादेशे ३९३ । ८७ द्वितीयायां च ३९० । ८८ प्रथमायाश्च द्विवचने भाषायाम् ३८७ । ८९ योऽचि ३९२ । ९० शेषे लोपः ३८५ । ९१ मपर्यन्तस्य ३८३ । ९२ युवावौ द्विवचने ३८६ । ९३ यूयवयौ जसि ३८८ । ९४ त्वाहौ सौ ३८४ । ९५ तुभ्यमह्यौ ङयि ३९४ । ९६ तवममौ ङसि ३९८ । ९७ त्वमावेकवचने ३८९ । ९८ प्रत्ययोत्तरपदयोश्च १३७२ । ९९ त्रिचतुरोः स्त्रियां तिसृचतसृ २९८ । १०० अचि र ऋतः २९९ ॥ ५ ॥ १०१ जराया जरसन्यतरस्याम् २२७ । १०२ त्यदादीनामः २६५ । १०३ किमः कः ३४२ । १०४ कु तिहोः १९५४ । १०५ क्वाति १९६० । १०६ तदोः सः सावनन्त्ययोः ३८१ । १०७ अदस औ सुलोपश्च ४३७ । १०८ इदमो मः ३४३ । १०९ दश्च ३४५ । ११० यः सौ ४४१ । १११ इदोऽय्पुंसि ३४४ । ११२ अनाप्यकः ३४६ । ११३ हलि लोपः ३४७ । ११४ मृजेर्वृद्धिः २४७३ । ११५ अचो ञ्णिति २५४ । ११६ अत उपधायाः २२८२ । ११७ तद्धितेष्वचामादेः १०७५ । ११८ किति च १०७६ ॥ सिचि प्रभाविट् सन्यचस्तास्वदातो जराया अष्टादश ॥

तृतीयः पादः ।

१ देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् १४३९ । २ केकयमित्रयुप्रलयानां यादे-

यिः ११४४ । ३ न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् १०९८ । ४ द्वारादीनां च १३८६ । ५ न्यग्रोधस्य च केवलस्य १५४३ । ६ न कर्मव्यतिहारे ३२१७ । ७ स्वागतादीनां च १५४९ । ८ श्वादेरिञि १५६० । ९ पदान्तस्यान्यतरस्याम् १५६१ । १० उत्तरपदस्य १३९६ । ११ अवयवादृतोः १३९७ । १२ सुसर्वार्धाज्जनपदस्य १३९८ । १३ दिशोऽमद्राणाम् १३९९ । १४ प्राचां ग्रामनगराणाम् १४०० । १५ संख्यायाः संवत्सरसंख्यस्य च १७५२ । १६ वर्षस्याभविष्यति १७५४ । १७ परिमाणान्तस्यासंज्ञाशाणयोः १६८३ । १८ जे प्रोष्ठपदानाम् १४०९ । १९ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ११३३ । २० अनुशतिकादीनां च १४३८ ॥ १ ॥ २१ देवताद्वन्द्वे च १२३९ । २२ नेन्द्रस्य परस्य १२४० । २३ दीर्घाच्च वरुणस्य १२४१ । २४ प्राचां नगरान्ते १४३१ । २५ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् १४३२ । २६ अर्धात्परिमाणस्य पूर्वस्य तु वा १६८४ । २७ नातः परस्य १६८५ । २८ प्रवाहणस्य ढे ११२९ । २९ तत्प्रत्ययस्य च ११३० । ३० नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् १४६० । ३१ यथातथयथापुरयोः पर्यायेण १७८९ । ३२ हनस्तोऽचिण्णलोः २५७४ । ३३ आतो युक्चिण्कृतोः २७६१ । ३४ नोदात्तोपदेशस्य मान्तस्यानाचमेः २७६३ । ३५ जनिवध्योश्च २५१२ । ३६ अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ २५७० । ३७ शाच्छासाह्वाव्यावेपां युक् २५८५ । ३८ वो विधूनने जुक् २५९० । ३९ लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने २५९१ । ४० भियो हेतुभये षुक् २५९५ ॥ २ ॥ ४१ स्फायो वः २५९७ । ४२ शदेरगतौ तः २५९८ । ४३ रुहः पोऽन्यतरस्याम् २५९९ । ४४ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ४६३ । ४५ न यासयोः ४६४ । ४६ उदीचामातः स्थाने यकपूर्वायाः ४६५ । ४७ भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि ४६६ । ४८ अभाषितपुंस्काच्च ४६७ । ४९ आदाचार्याणाम् ४६८ । ५० ठस्येकः ११७० । ५१ इसुसुक्तान्तात्कः १२२१ । ५२ चजोः कु घिण्यतोः २८६३ । ५३ न्यङ्क्वादीनां च २८६४ । ५४ हो हन्तेर्ञ्णिन्नेषु ३५८ । ५५ अभ्यासाच्च २४३० । ५६ हेरचङि २५३१ । ५७ सन्लिटोर्जेः २३३१ । ५८ विभाषा चेः २५२५ । ५९ न क्वादेः २८७५ । ६० अजिव्रज्योश्च २८७६ ॥ ३ ॥ ६१ भुजन्युब्जौ पाण्युपतापयोः २८७७ । ६२ प्रयाजानुयाजौ यज्ञाङ्गे २८७८ । ६३ वञ्चेर्गतौ २८७९ । ६४ ओक उचः के २८८० । ६५ ण्य आवश्यके २८८१ । ६६ यजयाचरुचप्रवचर्चश्च २८८२ । ६७ वचोऽशब्दसंज्ञायाम् २८८३ । ६८ प्रयोज्यनियोज्यौ शक्यार्थे २८८४ । ६९ भोज्यं भक्ष्ये २८८५ । ७० घोर्लोपो लेटि वा ३५८४ । ७१ ओतः श्यनि २५१० । ७२ क्सस्याचि २३३७ । ७३ लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये २३६५ । ७४ शमामष्टानां दीर्घः श्यनि २५१९ । ७५ ष्ठिवुक्लमुचमां शिति २३२० । ७६ क्रमः परस्मैपदेषु २३२२ । ७७ इषुगमियमां छः २४०० । ७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः २३६० । ७९ ज्ञाजनोर्जा २५११ । ८० प्वादीनां ह्रस्वः २५५८ ॥ ४ ॥ ८१ मीनातेर्निगमे ३५८५ । ८२ मिदेर्गुणः २३४६ । ८३ जुसि च २४८१ । ८४ सार्वधातुकार्धधातुकयोः २१६८ । ८५ जाग्रोऽविचिण्णल्ङित्सु २४८० । ८६ पुगन्तलघूपधस्य च २१८९ । ८७ नाभ्यस्तस्याचि पिति सार्वधातुके २५०३ । ८८ भूसुवोस्तिङि २२३४ । ८९ उतो वृद्धिर्लुकि हलि २४४३ । ९० ऊर्णोतेर्विभाषा २४४५ । ९१ गुणोऽपृक्ते २४४८ । ९२ तृणह इम् २५४५ । ९३ ब्रुव ईट् २४५२ । ९४ यङो वा २६५१ । ९५ तुरुस्तु-

श्म्यमः सार्वधातुके २४४४ । ९६ अस्तिसिचोऽपृक्ते २२२५ । ९७ बहुलं छन्दसि ३५८६ । ९८ रुदश्च पञ्चभ्यः २४७५ । ९९ अड्गार्ग्यगालवयोः २४७६ । १०० अदः सर्वेषाम् २४२६ । ॥ ५ ॥ १०१ अतो दीर्घो यञि २१७० । १०२ सुपि च २०२ । १०३ बहुवचने झल्येत् २०५ । १०४ ओसि च २०७ । १०५ आङि चापः २८९ । १०६ संबुद्धौ च २८८ । १०७ अम्बार्थनद्योर्ह्रस्वः २६७ । १०८ ह्रस्वस्य गुणः २४२ । १०९ जसि च २४१ । ११० ऋतो ङिसर्वनामस्थानयोः २७५ । १११ घेर्ङिति २४५ । ११२ आण्नद्याः २६८ । ११३ याडापः २९० । ११४ सर्वनाम्नः स्याड्ढ्रस्वश्च २९१ । ११५ विभाषा द्वितीयातृतीयाभ्याम् २९३ । ११६ ङेराम्नद्याम्नीभ्यः २७० । ११७ इदुद्भ्याम् २९७ । ११८ औत् २९६ । ११९ अच्च घेः २४७ । १२० आङो नाऽस्त्रियाम् २४४ ॥ ६ ॥ देविकादेवतास्फायो भुजमीनातेरतो दीर्घो विंशतिः ॥

चतुर्थः पादः ।

१ णौ चङ्युपधाया ह्रस्वः २३१४ । २ नाग्लोपिशास्वृदिताम् २५७२ । ३ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् २५६५ । ४ लोपः पिबतेरीच्चाभ्यासस्य २५८७ । ५ तिष्ठतेरित् २५८८ । ६ जिघ्रतेर्वा २५८९ । ७ उर्ऋत् २५६७ । ८ नित्यं छन्दसि ३५८७ । ९ दयतेर्दिगि लिटि २३८८ । १० ऋतश्च संयोगादेर्गुणः २३७९ । ११ ऋच्छत्यॄताम् २३८३ । १२ शॄदॄप्रां ह्रस्वो वा २४९५ । १३ केऽणः ८३४ । १४ न कपि ८३५ । १५ आपोऽन्यतरस्याम् ८९२ । १६ ऋदृशोऽङि गुणः २४०६ । १७ अस्यतेस्थुक् २५२० । १८ श्वयतेरः २४२१ । १९ पतः पुम् २३५५ । २० वच उम् २४५४ ॥ १ ॥ २१ शीङः सार्वधातुके गुणः २४४१ । २२ अयङ् यि क्ङिति २६४९ । २३ उपसर्गाद्ध्रस्व ऊहतेः २७०२ । २४ एतेर्लिङि २४५७ । २५ अकृत्सार्वधातुकयोर्दीर्घः २२९८ । २६ च्वौ च २१२० । २७ रीङृतः १२३४ । २८ रिङ् शयग्लिङ्क्षु २३६७ । २९ गुणोऽर्तिसंयोगाद्योः २३८० । ३० यङि च २६३२ । ३१ ई घ्राध्मोः २६४८ । ३२ अस्य च्वौ २११८ । ३३ क्यचि च २६५८ । ३४ अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु २६६१ । ३५ न च्छन्दस्यपुत्रस्य ३५८८ । ३६ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ३५८९ । ३७ अश्वाघस्यात् ३५९० । ३८ देवसुम्नयोर्यजुषि काठके ३५९१ । ३९ कव्यध्वरपृतनस्यर्चि लोपः ३५९२ । ४० द्यतिस्यतिमास्थामित्ति किति ३०७४ ॥ २ ॥ ४१ शाच्छोरन्यतरस्याम् ३०७५ । ४२ दधातेर्हिः ३०७६ । ४३ जहातेश्च क्त्वि ३३३१ । ४४ विभाषा छन्दसि ३५९३ । ४५ सुधितवसुधितनेमधितधिष्वधिषीय च ३५९४ । ४६ दो दद्घोः ३०७७ । ४७ अच उपसर्गात्तः ३०७८ । ४८ अपो भि ४४२ । ४९ सः स्यार्धधातुके २३४२ । ५० तासस्त्योर्लोपः २१९१ । ५१ रि च २१९२ । ५२ ह एति २२५० । ५३ यीवर्णयोर्दीधीवेव्योः २४८८ । ५४ सनि मीमाघुरभलभशकपतपदामच इस् २६२३ । ५५ आप्ज्ञप्यृधामीत् २६१९ । ५६ दम्भ इच्च २६२१ । ५७ मुचोऽकर्मकस्य गुणो वा २६२४ । ५८ अत्र लोपोऽभ्यासस्य २६२० । ५९ ह्रस्वः २१८० । ६० हलादिः शेषः २१७९ ॥ ३ ॥ ६१ शर्पूर्वाः खयः २२५९ । ६२ कुहोश्चुः २२४५ । ६३ न कवतेर्यङि २६४१ । ६४ कृषेश्छन्दसि ३५९५ । ६५ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरीत्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च ३५९६ । ६६ उरत् २२४४ । ६७ द्युतिस्वाप्योः संप्रसारणम्

२३४४ । ६८ व्यथो लिटि २३९३ । ६९ दीर्घ इणः किति २४९६ । ७० अत आदेः २२४८ । ७१ तस्मान्नुड् द्विहलः २२८८ । ७२ अश्नोतेश्च २५३३ । ७३ भवतेरः २१८१ । ७४ ससूवेति निगमे ३५९७ । ७५ निजां त्रयाणां गुणः श्लौ २५०२ । ७६ भृञामित् २४९६ । ७७ अर्तिपिपर्त्योश्च २४९३ । ७८ बहुलं छन्दसि ३५९८ । ७९ सन्यतः २३१७ । ८० ओः पुयण्ज्यपरे २५७७ ॥ ४ ॥ ८१ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा २५७८ । ८२ गुणो यङ्लुकोः २६३० । ८३ दीर्घोऽकितः २६३२ । ८४ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् २६४२ । ८५ नुगतोऽनुनासिकान्तस्य २६४३ । ८६ जपजभदहदशभञ्जपशां च २६३८ । ८७ चरफलोश्च २६३६ । ८८ उत्परस्यातः २६३७ । ८९ ति च ३०३७ । ९० रीगृदुपधस्य च २६४४ । ९१ स्रुग्रिकौ च लुकि २६५२ । ९२ ऋतश्च २६५३ । ९३ सन्वल्लघुनि चङ्परेऽनग्लोपे २३१६ । ९४ दीर्घो लघोः २३१८ । ९५ अत्स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् २५६६ । ९६ विभाषा वेष्टिचेष्ट्योः २५८३ । ९७ ई च गणः २५७३ ॥ णौ चशीङः शाच्छोः शर्पूर्वाः स्रवतिसप्तदश ॥

इति सप्तमोऽध्यायः।

अष्टमोऽध्यायः।

प्रथमः पादः।

१ सर्वस्य द्वे २१३९ । २ तस्य परमाम्रेडितम् ८३ । ३ अनुदात्तं च ३६७० । ४ नित्यवीप्सयोः २१४० । ५ परेर्वर्जने २१४१ । ६ प्रसमुपोदः पादपूरणे ३५९९ । ७ उपर्यध्यधसः सामीप्ये २१४२ । ८ वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु २१४३ । ९ एकं बहुव्रीहिवत् । २१४४ । १० आबाधे च २१४५ । ११ कर्मधारयवदुत्तरेषु २१४६ । १२ प्रकारे गुणवचनस्य २१४७ । १३ अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् २१४८ । १४ यथास्वे यथायथम् २१४९ । १५ द्वंद्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु २१५० । १६ पदस्य ४०१ । १७ पदात् ४०२ । १८ अनुदात्तं सर्वमपादादौ ४०३ । १९ आमन्त्रितस्य च ३६५५ । २० युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ ४०४ ॥ १ ॥ २१ बहुवचनस्य वस्नसौ ४०५ । २२ तेमयावेकवचनस्य ४०६ । २३ त्वामौ द्वितीयायाः ४०७ । २४ न चवाहाहैवयुक्ते ४०८ । २५ पश्यार्थैश्चानालोचने ४०९ । २६ सपूर्वायाः प्रथमाया विभाषा ४१० । २७ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ३९३४ । २८ तिङ्ङतिङः ३९३५ । २९ न लुट् ३९३६ । ३० निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ३९३७ । ३१ नह प्रत्यारम्भे ३९३८ । ३२ सत्यं प्रश्ने ३९३९ । ३३ अङ्गाप्रातिलोम्ये ३९४० । ३४ हिं च ३९४१ । ३५ छन्दस्यनेकमपि साकाङ्क्षम् ३९४२ । ३६ यावद्यथाभ्याम् ३९४३ । ३७ पूजायां नानन्तरम् ३९४४ । ३८ उपसर्गव्यपेतं च ३९४५ । ३९ तुपश्यपश्यताहैः पूजायाम् ३९४६ । ४० अहो च ३९४७ ॥ २ ॥ ४१ शेषे विभाषा ३९४८ । ४२ पुरा च परीप्सायाम् ३९४९ । ४३ नन्वित्यनुज्ञैषणायाम् ३९५० । ४४ किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ३९५१ । ४५ लोपे विभाषा ३९५२ । ४६ एहिमन्ये प्रहासे लृट् ३९५३ । ४७ जात्वपूर्वम् ३९५४ । ४८ किंवृत्तं च चिदुत्तरम् ३९५५ । ४९ आहो उताहो चान-

न्तरम् ३९५६ । ५० शेषे विभाषा ३९५७ । ५१ गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् ३९५८ । ५२ लोट् च ३९५९ । ५३ विभाषितं सोपसर्गमनुत्तमम् ३९६० । ५४ हन्त च ३९६१ । ५५ आम एकान्तरमामन्त्रितमनन्तिके ३९६२ । ५६ यद्धितुपरं छन्दसि ३९६३ । ५७ चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ३९६४ । ५८ चादिषु च ३९६५ । ५९ चवायोगे प्रथमा ३९६६ । ६० हेति क्षियायाम् ३९६७ ॥ ३ ॥ ६१ अहेति विनियोगे च ३९६८ । ६२ चाहलोप एवेत्यवधारणम् ३९६९ । ६३ चादिलोपे विभाषा ३९७० । ६४ नैवावेति च च्छन्दसि ३९७१ । ६५ एकान्याभ्यां समर्थाभ्याम् ३९७२ । ६६ यद्वृत्तान्नित्यम् ३९७३ । ६७ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ३९७४ । ६८ सगतिरपि तिङ् ३९७५ । ६९ कुत्सने च सुप्यगोत्रादौ ३९७६ । ७० गतिर्गतौ ३९७७ । ७१ तिङि चोदात्तवति ३९७८ । ७२ आमन्त्रितं पूर्वमविद्यमानवत् ४१२ । ७३ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ४१३ । ७४ विभाषितं विशेषवचने बहुवचनम् ३६९९ ॥ सर्वस्य बहुवचनस्य शेषेऽहेति चतुर्दश ॥

द्वितीयः पादः ।

१ पूर्वत्रासिद्धम् १२ । २ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ३५३ । ३ न मु ने ४३९ । ४ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ३६५७ । ५ एकादेश उदात्तेनोदात्तः ३६५८ । ६ स्वरितो वानुदात्ते पदादौ ३६५९ । ७ नलोपः प्रातिपदिकान्तस्य २३६ । ८ न ङिसंबुद्ध्योः ३९२ । ९ मादुपधायाश्च मतोर्वोऽयवादिभ्यः १८९७ । १० झयः १८९८ । ११ संज्ञायाम् १८९९ । १२ आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती १९०० । १३ उदन्वानुदधौ च १९०१ । १४ राजन्वान्सौराज्ये १९०२ । १५ छन्दसीरः ३६०० । १६ अनो नुट् ३६०१ । १७ नाद्धस्य ३६०२ । १८ कृपो रो लः २३५० । १९ उपसर्गस्यायतौ २३२६ । २० ग्रो यङि २६३९ ॥ १ ॥ २१ अचि विभाषा २५४१ । २२ परेश्च घाङ्कयोः ३२६२ । २३ संयोगान्तस्य लोपः ५४ । २४ रात्सस्य २८० । २५ धि च २२४९ । २६ झलो झलि २२८१ । २७ ह्रस्वादङ्गात् २३६९ । २८ इट ईटि २२६६ । २९ स्कोः संयोगाद्योरन्ते च ३८० । ३० चोः कुः ३७८ । ३१ हो ढः ३२४ । ३२ दादेर्धातोर्घः ३२५ । ३३ वा द्रुहमुहष्णुहष्णिहाम् ३२७ । ३४ नहो धः ४४० । ३५ आहस्थः २४५१ । ३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः २९४ । ३७ एकाचो बशो भष्झषन्तस्य स्ध्वोः ३२६ । ३८ दधस्तथोश्च २५०१ । ३९ झलां जशोऽन्ते ८४ । ४० झषस्तथोर्धोऽधः २२८० ॥ २ ॥ ४१ षढोः कः सि २९५ । ४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ३०१६ । ४३ संयोगादेरातो धातोर्यण्वतः ३०१७ । ४४ ल्वादिभ्यः ३०१८ । ४५ ओदितश्च ३०१९ । ४६ क्षियो दीर्घात् ३०१९ । ४७ श्योऽस्पर्शे ३०२१ । ४८ अञ्चोऽनपादाने ३०२४ । ४९ दिवोऽविजिगीषायाम् ३०२८ । ५० निर्वाणोऽवाते ३०२९ । ५१ शुषः कः ३०३० । ५२ पचो वः ३०३१ । ५३ क्षायो मः ३०३२ । ५४ प्रस्त्योऽन्यतरस्याम् ३०३४ । ५५ अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ३०३५ । ५६ नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ३०३८ । ५७ न ध्याख्यापृमूर्च्छिमदाम् ३०४० । ५८ वित्तो भोगप्रत्यययोः ३०४१ । ५९ भित्तं शकलम् ३०४२ । ६० ऋणमाधमर्ण्ये ३०४३ ॥ ३ ॥ ६१ नसत्तनिषत्ता-

नुत्तप्रत्तमूर्तगूर्तानि छन्दसि ३६०३ । ६२ क्विन्प्रत्ययस्य कुः ३७७ । ६३ नशेर्वा ४३१ । ६४ मो नो धातोः ३४१ । ६५ म्वोश्च २३०९ । ६६ ससजुषो रुः १६२ । ६७ अवयाः श्वेतवाः पुरोडाश्च ३४१६ । ६८ अहन् ४४३ । ६९ रोऽसुपि १७२ । ७० अम्नरूधरवरित्युभयथा छन्दसि ३६०४ । ७१ भुवश्च महाव्याहृतेः ३६०५ । ७२ वसुस्रंसुध्वंस्वनडुहां दः ३३४ । ७३ तिप्यनस्तेः २४८४ । ७४ सिपि धातो रुर्वा २४८५ । ७५ दश्च २४६८ । ७६ र्वोरुपधाया दीर्घ इकः ४३३ । ७७ हलि च ३५४ । ७८ उपधायां च २२६९ । ७९ न भकुर्छुराम् १६२९ । ८० अदसोऽसेर्दादु दो मः ४१९ ॥ ४ ॥ ८१ एत ईद्बहुवचने ४३८ । ८२ वाक्यस्य टेः प्लुत उदात्तः ९३ । ८३ प्रत्यभिवादेऽशूद्रे ९४ । ८४ दूराद्धूते च ९५ । ८५ हैहेप्रयोगे हैहयोः ९६ । ८६ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ९७ । ८७ ओमभ्यादाने ३६०६ । ८८ ये यज्ञकर्मणि ३६०७ । ८९ प्रणवष्टेः ३६०८ । ९० याज्यान्तः ३६०९ । ९१ ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ३६१० । ९२ अग्नीत्प्रेषणे परस्य च ३६११ । ९३ विभाषा पृष्टप्रतिवचने हेः ३६१२ । ९४ निगृह्यानुयोगे च ३६१३ । ९५ आम्रेडितं भर्त्सने ३६१४ । ९६ अङ्गयुक्तं तिङाकाङ्क्षम् ३६१५ । ९७ विचार्यमाणानाम् ३६१६ । ९८ पूर्वं तु भाषायाम् ३६१७ । ९९ प्रतिश्रवणे च ३६१८ । १०० अनुदात्तं प्रश्नान्ताभिपूजितयोः ३६१९ ॥ ५ ॥ १०१ चिदिति चोपमार्थे प्रयुज्यमाने ३६२० । १०२ उपरिस्विदासीदिति च ३६२१ । १०३ स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु ३६२२ । १०४ क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् ३६२३ । १०५ अनन्त्यस्यापि प्रश्नाख्यानयोः ३६२४ । १०६ प्लुतावैच इदुतौ ३६२५ । १०७ एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ३६२६ । १०८ तयोर्य्वावचि संहितायाम् ३६२७ ॥ पूर्वत्राचि षढोर्नसनेत ईचिदित्यष्टौ ॥

तृतीयः पादः ।

१ मतुवसो रु संबुद्धौ छन्दसि ३६२८ । २ अत्रानुनासिकः पूर्वस्य तु वा १३६ । ३ आतोऽटि नित्यम् ३६३२ । ४ अनुनासिकात्परोऽनुस्वारः १३७ । ५ समः सुटि १३५ । ६ पुमः खय्यम्परे १३९ । ७ नश्छव्यप्रशान् १४० । ८ उभयथर्क्षु ३६३० । ९ दीर्घादटि समानपादे ३६३१ । १० नॄन्पे १४१ । ११ स्वतवान्पायौ ३६३३ । १२ कानाम्रेडिते १४३ । १३ ढो ढे लोपः २३३५ । १४ रो रि १७३ । १५ खरवसानयोर्विसर्जनीयः ७६ । १६ रोः सुपि ३३९ । १७ भोभगोअघोअपूर्वस्य योऽशि १६७ । १८ व्योर्लघुप्रयत्नतरः शाकटायनस्य १६८ । १९ लोपः शाकल्यस्य ६७ । २० ओतो गार्ग्यस्य १६९ ॥ १ ॥ २१ उञि च पदे १७० । २२ हलि सर्वेषाम् १७१ । २३ मोऽनुस्वारः १२२ । २४ नश्चापदान्तस्य झलि १२३ । २५ मो राजि समः क्वौ १२६ । २६ हे मपरे वा १२७ । २७ नपरे नः १२९ । २८ ङ्णोः कुक्टुक्शरि १३० । २९ डः सि धुट् १३१ । ३० नश्च १३२ । ३१ शि तुक् १३३ । ३२ ङमो ह्रस्वादचि ङमुण्नित्यम् १३४ । ३३ मय उञो वो वा १०८ । ३४ विसर्जनीयस्य सः १३८ । ३५ शर्परे विसर्जनीयः १५० । ३६ वा शरि १५१ । ३७ कुप्वोः ≍क≍पौ च १४२ । ३८ सोऽपदादौ १५२ । ३९ इणः षः १५३ । ४० नमस्पुरसोर्गत्योः १५४ ॥ २ ॥ ४१ इदुदुपधस्य चाप्रत्ययस्य १५५ । ४२ तिरसोऽन्यतरस्याम् १५६ । ४३ द्विस्त्रिश्चतुरिति कृत्वोऽर्थे १५७ । ४४ इसुसोः सामर्थ्ये १५८ । ४५ नित्यं समासेऽनुत्तरप-

दस्थस्य १५९ । ४६ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य १६० । ४७ अधश्शिरसी पदे १६१ । ४८ कस्कादिषु च १४४ । ४९ छन्दसि वाम्रेडितयोः ३६३४ । ५० कःकरत्करतिकृधिकृतेष्वनदितेः ३६३५ । ५१ पञ्चम्याः परावध्यर्थे ३६३६ । ५२ पातौ च बहुलम् ३६३७ । ५३ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ३६३८ । ५४ इडाया वा ३६३९ । ५५ अपदान्तस्य मूर्धन्यः २१० । ५६ सहेः साडः सः ३३५ । ५७ इण्कोः २११ । ५८ नुम्विसर्जनीयशर्व्यवायेऽपि ४३४ । ५९ आदेशप्रत्यययोः २१२ । ६० शासिवसिघसीनां च २४१० ॥ ३ ॥ ६१ स्तौतिण्योरेव षण्यभ्यासात् २६२७ । ६२ सः स्विदिस्वदिसहीनां च २६२८ । ६३ प्राक्सितादड्व्यवायेऽपि २२७६ । ६४ स्थादिष्वभ्यासेन चाभ्यासस्य २२७७ । ६५ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् २२७० । ६६ सदिरप्रतेः २२७१ । ६७ स्तन्भेः २२७२ । ६८ अवाच्चालम्बनाविदूर्ययोः २२७३ । ६९ वेश्च स्वनो भोजने २२७४ । ७० परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् २२७५ । ७१ सिवादीनां वाड्व्यवायेऽपि २३५९ । ७२ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु २३४९ । ७३ वेः स्कन्देरनिष्ठायाम् २३९८ । ७४ परेश्च २३९९ । ७५ परिस्कन्दः प्राच्यभरतेषु ३०२६ । ७६ स्फुरतिस्फुलत्योर्निर्निविभ्यः २५३७ । ७७ वेः स्कभ्नातेर्नित्यम् २५५६ । ७८ इणः षीध्वंलुङ्लिटां धोऽङ्गात् २२४७ । ७९ विभाषेटः २३२५ । ८० समासेऽङ्गुलेः सङ्गः १०१९ ॥ ४ ॥ ८१ भीरोः स्थानम् १०२० । ८२ अग्नेः स्तुत्स्तोमसोमाः ९२४ । ८३ ज्योतिरायुषः स्तोमः १०२१ । ८४ मातृपितृभ्यां स्वसा ९८४ । ८५ मातुःपितुर्भ्यामन्यतरस्याम् ९८३ । ८६ अभिनिसः स्तनः शब्दसंज्ञायाम् २१९३ । ८७ उपसर्गप्रादुर्भ्यामस्तिर्यच्परः २४७२ । ८८ सुविनिर्दुर्भ्यः सुपिसूतिसमाः २४७७ । ८९ निनदीभ्यां स्नातेः कौशले ३०८२ । ९० सूत्रं प्रतिष्णातम् ३०८३ । ९१ कपिष्ठलो गोत्रे ३०८४ । ९२ प्रष्ठोऽग्रगामिनि २९१७ । ९३ वृक्षासनयोर्विष्टरः ३२३३ । ९४ छन्दोनाम्नि च ३२०६ । ९५ गवियुधिभ्यां स्थिरः ९६७ । ९६ विकुशमिपरिभ्यः स्थलम् ३०८५ । ९७ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः २९१८ । ९८ सुषामादिषु च १०२२ । ९९ एति संज्ञायामगात् १०२३ (ग २५३) । १०० नक्षत्राद्वा १०२४ (ग२५३) ॥ ५ ॥ १०१ ह्रस्वात्तादौ तद्धिते १२२५ । १०२ निसस्तपतावनासेवने २४०३ । १०३ युष्मत्तत्ततक्षुःष्वन्तःपादम् ३६४० । १०४ यजुष्येकेषाम् ३६४१ । १०५ स्तुतस्तोमयोश्छन्दसि ३६४२ । १०६ पूर्वपदात् ३६४३ । १०७ सुञः ३६४४ । १०८ सनोतेरनः ३६४५ । १०९ सहेः पृतनर्ताभ्यां च ३६४६ । ११० न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ३१६८ । १११ सात्पदाद्योः २१२३ । ११२ सिचो यङि २६४० । ११३ सेधतेर्गतौ २२७८ । ११४ प्रतिस्तब्धनिस्तब्धौ च ३०२७ । ११५ सोढः २३५८ । ११६ स्तम्भुसिवुसहां चङि २५८० । ११७ सुनोतेः स्यसनोः २५२४ । ११८ सदेः परस्य लिटि २३६१ । ११९ निव्यभिभ्योऽड्व्यवाये वा छन्दसि ३६४७ ॥ सतुवसोरूत्रि चेदुदुपधस्य स्तौतिण्योर्भीरोर्ह्रस्वात्तादावेकोनविंशतिः ॥

चतुर्थः पादः ।

१ रषाभ्यां नो णः समानपदे २३५ । २ अट्कुप्वाङ्नुम्व्यवायेऽपि १९७ । ३ पूर्वपदात्संज्ञायामगः ८५७ । ४ वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः १०३९ । ५ प्रनि-

रन्तःशरेक्षुप्लक्षाम्रकार्ष्यखादिरपीयूक्षाभ्योऽसंज्ञायामपि १०५० । ६ विभाषौषधिवनस्पतिभ्यः १०५१ । ७ अह्नोऽदन्तात् ७९१ । ८ वाहनमाहितात् १०५२ । ९ पानं देशे १०५३ । १० वा भावकरणयोः १०५४ । ११ प्रातिपदिकान्तनुम्विभक्तिषु च १०५५ । १२ एकाजुत्तरपदे णः ३०७ । १३ कुमति च १०५६ । १४ उपसर्गादसमासेऽपि णोपदेशस्य २२८७ । १५ हिनुमिना २५३० । १६ आनि लोट् २२३१ । १७ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च २२८५ । १८ शेषे विभाषाकखादावषान्त उपदेशे २२३२ । १९ अनितेः २४७८ । २० अन्तः २९८४ ॥ १ ॥ २१ उभौ साभ्यासस्य २६०६ । २२ हन्तेरत्पूर्वस्य ३५९ । २३ वमोर्वा २४२९ । २४ अन्तरदेशे ३३५४ । २५ अयनं च ३२९५ । २६ छन्दस्यृदवग्रहात् ३६४८ । २७ नश्च धातुस्थोरुषुभ्यः ३६४९ । २८ उपसर्गाद्बहुलम् ८५९ । २९ कृत्यचः २८३५ । ३० णेर्विभाषा २८३६ । ३१ हलश्चेजुपधात् २८३७ । ३२ इजादेः सनुमः २८३८ । ३३ वा निंसनिक्षनिन्दाम् २८३९ । ३४ न भाभूपूकमिगमिप्यायीवेपाम् २८४० । ३५ षात्पदान्तात् ३३१० । ३६ नशेः षान्तस्य २५१८ । ३७ पदान्तस्य १९८ । ३८ पदव्यवायेऽपि १०५७ । ३९ क्षुभ्नादिषु च ७९२ । ४० स्तोः श्चुना श्चुः १११ ॥ २ ॥ ४१ ष्टुना ष्टुः ११३ । ४२ न पदान्ताट्टोरनाम् ११४ । ४३ तोः षि ११५ । ४४ शात् ११२ । ४५ यरोऽनुनासिकेऽनुनासिको वा ११६ । ४६ अचो रहाभ्यां द्वे ५९ । ४७ अनचि च ४८ । ४८ नादिन्याक्रोशे पुत्रस्य ५५ । ४९ शरोऽचि ३४० । ५० त्रिप्रभृतिषु शाकटायनस्य ५६ । ५१ सर्वत्र शाकल्यस्य ५७ । ५२ दीर्घादाचार्याणाम् ५८ । ५३ झलां जश्झशि ५२ । ५४ अभ्यासे चर्च २१८२ । ५५ खरि च १२१ । ५६ वावसाने २०६ । ५७ अणोऽप्रगृह्यस्यानुनासिकः ११० । ५८ अनुस्वारस्य ययि परसवर्णः १२४ । ५९ वा पदान्तस्य १२५ । ६० तोर्लि ११७ ॥ ३ ॥ ६१ उदः स्थास्तम्भोः पूर्वस्य ११८ । ६२ झयो होऽन्यतरस्याम् ११९ । ६३ शश्छोऽटि १२० । ६४ हलो यमां यमि लोपः ६० । ६५ झरो झरि सवर्णे ७१ । ६६ उदात्तादनुदात्तस्य स्वरितः ३६६० । ६७ नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् ३६६१ । ६८ अ अ इति ११ ॥ रषाभ्यामुभौ ष्टुना ष्टुरुदः स्थाष्टौ ॥

इत्यष्टमोऽध्यायः ।

इति श्रीपाणिनिमुनिप्रणीतोऽष्टाध्यायीसूत्रपाठः समाप्तः ।

---

(२) पाणिनीयो गणपाठः ।

प्रथमोऽध्यायः ।

१ । २७ सर्वादीनि सर्वनामानि २१३ ॥ सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥ इति सर्वादिः ॥ १ ॥

१ । ३७ स्वरादिनिपातमव्ययम् ४४७ ॥ स्वर् अन्तर् प्रातर् । अन्तोदात्ताः । पुनर् सनुत-

र् उच्चैस् नीचैस् शनैस् ऋधक् ऋते युगपत् आरात् [अन्तिकात्] पृथक् । आद्युदात्ताः । श्वस् श्वस् दिवा रात्रौ सायम् चिरम् मनाक् ईषत् [शश्वत्] जोषम् तूष्णीम् बहिस् अधस् (अवस्) समया निकषा स्वयम् मृषा नक्तम् नञ् हेतौ [हे है] इद्धा अद्धा सामि । अन्तोदात्ताः । वत् बत सनत् सनात् तिरस् । आद्युदात्ताः । अन्तरा । अन्तोदात्तः । [अन्तरेण] मक् ज्योक् योक् नक् कम् शम् सना सहसा श्रद्धा अलम् स्वधा वषट् विना नाना स्वस्ति अन्यत् अस्ति उपांशु क्षमा विहायसा दोषा मुधा दिष्ट्या वृथा मिथ्या । क्त्वातोसुन्कसुनः । कृन्मकारसंध्यक्षरान्तोऽव्ययीभावश्च । पुरा मिथो मिथस् [प्रायस् मुहुस्] प्रवाहुकम् [प्रवाहिका] आर्यहलम् अभीक्ष्णम् साकम् सार्धम् सत्रम् समम् नमस् हिरुक् । तसिलादयस्तद्धिता एधाच्पर्यन्ताः शस्तसी कृत्वसुच् सुच् आस्थालौ । च्व्यर्थाश्च । [अथ] अम् आम् प्रताम् [प्रतान्] प्रशान् । आकृतिगणोऽयम् । तेनान्येऽपि । तथाहि । माङ् श्रम् कामम् [प्रकामम्] भूयस् परम् साक्षात् साचि (सावि) सत्यम् मङ्क्षु संवत् अवश्यम् सपदि प्रादुस् आविस् अनिशम् नित्यम् नित्यदा सदा अजस्रम् संततम् उषा ओम् भूर् भुवर् झटिति तरसा सुष्ठु कु अञ्जसा अ मिथु (अमिथु) विथक् भाजक् अन्वक् चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरात् अस्तम् आनुषक् अनुषक् अनुषट् अम्नस् (अम्भस्) अम्मर् (अम्भर्) स्थाने वरम् दुष्ठु बलात् शु अर्वाक् शुदि वदि इत्यादि । तसिलादयः प्राक्पाशपः । शस्प्रभृतयः प्राक्समासान्तेभ्यः । मान्तः कृत्वोर्थः । तसिवती । नानाञाविति ॥ इति स्वरादिः ॥ २ ॥

४ । ५७ चादयोऽसत्त्वे २० ॥ च वा ह [अह] एव एवम् नूनम् शश्वत् युपत् (युगपत्) [भूयस्] सूपत् कूपत् कुवित् नेत् चेत् चण् कच्चित् यत्र तत्र नह हन्त माकिम् [माकीम्] माकिर् नाकिम् [नकीम्] नकिर् [आकीम्] माङ् नञ् तावत् यावत् त्वा त्वै त्वै [द्वै रै] रै श्रौषट् वौषट् वषट् स्वाहा स्वधा ओम् तथा (तथाहि) खलु किल अथ सु [सुष्ठु] स्म अ इ उ ऋ लृ ए ऐ ओ औ दह उञ् उकञ् वेलायाम् मात्रायाम् यथा यत् तत् किम् पुरा वधा (वध्वा) धिक् हाहा हेहै (हहे) पाट् प्याट् आहो उताहो हो अहो नो (नौ) अथो ननु मन्ये मिथ्या असि ब्रूहि तु नु इति इव वत् वात् वन बत [सम् वशम् शिकम् दिकम्] सनुकम् छंवट् (छंवट)शङ्के शुकम् खम् सनात् सनतर् नहिकम् सत्यम् ऋतम् अद्धा इद्धा नोचेत् नचेत् नहि जातु कथम् कुतः कुत्र अव अनु हा हे [है] आहोस्वित् शम् कम् खम् दिष्ट्या पशु वट् सह [अनुषट्] आनुषक् अङ्ग फट् ताजक् (भाजक्) अये अरे वाट् (चाटु) कुम् खुम् घुम् अम् ईम् सीम् सिम् सि वै । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः ॥ आकृतिगणोऽयम् ॥ इति चादयः ॥ ३ ॥

४।५८ प्रादयः २१ ॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप ॥ इति प्रादयः ॥ ४ ॥

४ । ६१ ऊर्यादिच्विडाचश्च ७६२ ॥ ऊरी उररी तन्थी ताली आताली वेताली धूली धूसी शकला संशकला ध्वंसकला भ्रंसकला गुलगुधा सजूस् फल फली विक्ली आक्ली आलोष्टी केवाली केवासी सेवासी (पर्याली) शेवाली वर्षाली अत्यूमशा वश्मसा [मस्मसा] मसमसा औषट् (श्रौषट्) वौषट् वषट् स्वाहा स्वधा वन्धा प्रादुस् श्रत् आविस् ॥ इत्यूर्यादयः ॥ ५ ॥

४ । ७४ **साक्षात्प्रभृतीनि च ७७९** ॥ साक्षात् मिथ्या चिन्ता भद्रा रोचना आस्था अमा श्रद्धा प्राजर्या प्राजरुहा बीजर्या बीजरुहा संसर्या अर्थे लवणम् उष्णम् शीतम् उदकम् आर्द्रम् अग्नौ वशे विकसने प्रसहने प्रतपने प्रादुस् नमस् ॥ **आकृतिगणोऽयम्** ॥ **इति साक्षात्प्रभृतयः** ॥ ६ ॥

इति प्रथमोऽध्यायः ।

द्वितीयोऽध्यायः ।

१ । १७ **तिष्ठद्गुप्रभृतीनि च ६७१** ॥ तिष्ठद्गु वहद्गु आयतीगवम् खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृतयवम् संह्रियमाणयवम् संहृतबुसम् संह्रियमाणबुसम् समभूमि समपदाति सुषमम् विषमम् दुःषमम् निःषमम् अपसमम् आयतीसमम् [प्रौढम्] पापसमम् पुण्यसमम् प्राह्णम् प्ररथम् प्रमृगम् प्रदक्षिणम् [अपरदक्षिणम्] संप्रति असंप्रति । इच्प्रत्ययः समासान्तः ॥ **इति तिष्ठद्गुप्रभृतयः** ॥ ७ ॥

१ । ४० **सप्तमी शौण्डैः ७१७** ॥ शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर अधि पटु पण्डित कुशल चपल निपुण ॥ **इति शौण्डादयः** ॥ ८ ॥

१ । ४८ **पात्रेसमितादयश्च ७२९** ॥ पात्रेसमिताः पात्रेबहुलाः उदुम्बरमशकः (उदुम्बरमशकाः) उदुम्बरकृमिः कूपकच्छपः अवटकच्छपः कूपमण्डूकः कुम्भमण्डूकः उदपानमण्डूकः नगरकाकः नगरवायसः मातरिपुरुषः पिण्डीशूरः पितरिशूरः गेहेशूरः गेहेनर्दी गेहेक्ष्वेडी गेहेविजिती गेहेव्याडः गेहेमेही [गेहेदाही] गेहेदृप्तः गेहेधृष्टः गर्भेतृप्तः आखनिकबकः गोष्ठेशूरः गोष्ठेविजिती गोष्ठेक्ष्वेडी गोष्ठेपटुः गोष्ठेपण्डितः गोष्ठेप्रगल्भः कर्णेटिरिटिरा कर्णेचुरुचुरा ॥ **आकृतिगणोऽयम्** ॥ **इति पात्रेसमितादयः** ॥ ९ ॥

१ । ५६ **उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ७३९** ॥ व्याघ्र सिंह ऋक्ष ऋषभ चन्दन वृक वृष वराह हस्तिन् तरु कुञ्जर रुरु पृषत् पुण्डरीक पलाश कितव ॥ **इति व्याघ्रादयः** ॥ १० ॥ **आकृतिगणोऽयम्** । तेन । मुखपद्मम् मुखकमलम् करकिसलयम् पार्थिवचन्द्रः इत्यादि ॥

१ । ५९ **श्रेण्यादयः कृतादिभिः ७३८** ॥ श्रेणि [ऊक] पूग कुन्दुम (मुकुन्द) [राशि] निचय [विशेष] निधन (विधान) [पर] इन्द्र देव मुण्ड भूत श्रमण वदान्य अध्यापक अभिरूपक ब्राह्मण क्षत्रिय [विशिष्ट] पटु पण्डित कुशल चपल निपुण कृपण ॥ इत्येते **श्रेण्यादयः** ॥ ११ ॥ कृत मित मत भूत उक्त [युक्त] समाज्ञात समाम्नात समाख्यात संभावित [संसेवित] अवधारित अवकल्पित निराकृत उपकृत उपाकृत [दृष्ट कलित दलित उदाहृत विश्रुत उदित] ॥ **आकृतिगणोऽयम्** ॥ **इति कृतादयः** ॥ १२ ॥

१ । ६० **शाकपार्थिवादीनामुपसंख्यानम् (वा १३१४)** ॥ शाकपार्थिव कुतपसौश्रुत अजातौल्वलि । **आकृतिगणोऽयम्** । कृत्वापकृत भुक्तविभुक्त पीतविपीत गतप्रत्यागत यातानुयात क्रयाक्रयिका पुटापुटिका फलाफलिका [मानोन्मानिका] ॥ **इति शाकपार्थिवादयः** ॥ १३ ॥

१ । ७० **कुमारः श्रमणादिभिः ७५२** ॥ श्रमणा प्रव्रजिता कुलटा गर्भिणी तापसी

दासी बन्धकी अध्यापक अभिरूपक पण्डित पटु मृदु कुशल चपल निपुण ॥ इति श्रम-णादयः ॥ १४ ॥

१ । ७२ मयूरव्यंसकादयश्च ७९४ ॥ मयूरव्यंसक छात्रव्यंसक कम्बोजमुण्ड यवनमुण्ड- छन्दसि । हस्तेगृह्य (हस्तगृह्य) पादेगृह्य (पादगृह्य) लाङ्गूलेगृह्य (लाङ्गूलगृह्य) पुनर्दाय । एहीडादयोऽन्यपदार्थे । एहीडं वर्तते । एहियवं वर्तते । एहिवाणिजा क्रिया । अपेहिवाणिजा प्रेहिवाणिजा एहिस्वागता अपेहिस्वागता अपेहिद्वितीया प्रेहिद्वितीया एहिकटा अपेहिकटा प्रेहिकटा आहरकटा प्रेहिकर्दमा प्रोहकर्दमा विधमचूडा उद्धमचूडा (उद्धरचूडा) आहरचेला आहरवसना [आहरसेना] आहरवनिता (आहरविनता) कृन्तविचक्षणा उद्धरोत्सृजा उद्धरावसृजा उद्धमविधमा उत्पचनिपचा उत्पतनिपता उच्चावचम् उच्चनीचम् आचोपचम् आचपराचम् नखप्रचम् निश्चप्रचम् अकिंचन स्नात्वाकालक पीत्वास्थिरक भुक्त्वासुहित प्रोष्यपापीयान् उत्पत्यपाकला निपत्यरोहिणी निषण्णश्यामा अपेहिप्रघसा एहिविघसा इहपञ्चमी इहद्वितीया । जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति । जहिजोडः (जहिजोडम्) जहिस्तम्बम् (जाहिस्तम्बः) [उज्जहिस्तम्बम्] । आख्यातमाख्यातेन क्रियासातत्ये । अश्नीतपिबता पचतभृज्जता खादतमोदता खादतवमता (खादताचमता) आहरनिवपा आहरनिष्किरा (आवपनिष्किरा) उत्पचविपचा भिन्धिलवणा कृन्धिविचक्षणा पचलवणा पचप्रकूटा । आकृतिगणोऽयम् ॥ तेन । अकुतोभयः कान्दिशीकः (कान्देशीकः) आहोपुरुषिका अहमहमिका यदृच्छा एहिरेयाहिरा उन्मृजावमृजा द्रव्यान्तरम् अवश्यकार्यम् ॥ इति मयूरव्यंसकादयः ॥ १९ ॥

२ । ९ याजकादिभिश्च ७०३ ॥ याजक पूजक परिचारक परिवेषक (परिषेचक) स्नापक अध्यापक उत्साहक उद्वर्तक होतृ भर्तृ रथगणक पत्तिगणक ॥ इति याजकादयः ॥ १६ ॥

२ । ३१ राजदन्तादिषु परम् ९०२ ॥ राजदन्तः अग्रेवणम् लिप्तवासितम् नग्नमुषितम् सिक्तसंमृष्टम् मृष्टलुञ्चितम् अवक्लिन्नपक्वम् अर्पितोतम् उप्तगाढम् उलूखलमुसलम् तण्डुलकिण्वम् दृषदुपलम् आरड्वायनि (आरग्वायनबन्धकी) चित्ररथवाह्लीकम् अवन्त्यश्मकम् शूद्रार्यम् स्नातकराजानौ विष्वक्सेनार्जुनौ अक्षिभ्रुवम् दारगवम् शब्दार्थौ धर्मार्थौ कामार्थौ अर्थशब्दौ अर्थधर्मौ अर्थकामौ वैकारिमतम् गाजवाजम् (गोजवाजम्) गोपालिधानपूलासम् (गोपालधानीपूलासम्) पूलासकारण्डम् (पूलासककुरण्डम्) स्थूलासम् (स्थूलपूलासम्) उशीरबीजम् [जिज्ञास्थि] सिञ्जास्थम् (सिञ्जाश्वत्थम्) चित्रास्वाती (चित्रस्वाती) भार्यापती दंपती जंपती जायापती पुत्रपती पुत्रपशू केशश्मश्रू शिरोबिजु (शिरोबीजम्) शिरोजानु सर्पिर्मधुनी मधुसर्पिषी [आद्यन्तौ] अन्तादी गुणवृद्धी वृद्धिगुणौ ॥ इति राजदन्तादयः ॥ १७ ॥

२ । ३७ वाहिताग्न्यादिषु ९०० ॥ आहिताग्नि जातपुत्र जातदन्त जातश्मश्रु तैलपीत घृतपीत [मद्यपीत] ऊढभार्य गतार्थ । आकृतिगणोऽयम् । तेन । गडुकण्ठ अस्युद्यत (अस्युद्यत) दण्डपाणिप्रभृतयोऽपि ॥ इत्याहिताग्न्यादयः ॥ १८ ॥

२ । ३८ कडाराः कर्मधारये ७९१ ॥ कडार गडुल खञ्ज खोड काण कुण्ठ ख-

लति गौर वृद्ध भिक्षुक पिङ्ग पिङ्गुल (पिङ्गल) तड तनु [जठर] बधिर मठर कुब्ज बर्बर ॥ इति कडारादयः ॥ १९ ॥

३। १७ नौकाकान्नशुकशृगालवर्जेषु (वा १४६६) ॥ नौ काक अन्न शुक शृगाल ॥ इति नावादयः ॥ २० ॥

३। १८ प्रकृत्यादिभ्य उपसंख्यानम् (वा १४६८) ॥ प्रकृति प्राय गोत्र सम विषम द्विद्रोण पञ्चक साहस्र ॥ इति प्रकृत्यादयः ॥ २१ ॥

४। ११ गवाश्वप्रभृतीनि च ९१९ ॥ गवाश्वम् गवाविकम् गवैडकम् अजाविकम् [अजैडकम्] कुब्जवामनम् कुब्जकिरातम् पुत्रपौत्रम् श्वचण्डालम् स्त्रीकुमारम् दासीमाणवकम् शाटीपटीरम् शाटीप्रच्छदम् शाटीपट्टिकम् उष्ट्रखरम् उष्ट्रशशम् मूत्रशकृत् मूत्रपुरीषम् यकृन्मेदः मांसशोणितम् दर्भशरम् दर्भपूतीकम् अर्जुनशिरीषम् अर्जुनपुरुषम् तृणोपलम् (तृणोलपम्) दासीदासम् कुटीकुटम् भागवतीभागवतम् ॥ इति गवाश्वप्रभृतीनि ॥ २२ ॥

४। १४ न दधिपयआदीनि ९१८ ॥ दधिपयसी सर्पिर्मधुनी मधुसर्पिषी ब्रह्मप्रजापती शिववैश्रवणौ स्कन्दविशाखौ परिव्राजककौशिकौ (परिव्राट्कौशिकौ) प्रवर्ग्योपसदौ शुक्लकृष्णौ इध्माबर्हिषी दीक्षातपसी [श्रद्धातपसी मेधातपसी] अध्ययनतपसी उलूखलमुसले आद्यवसाने श्रद्धामेधे ऋक्सामे वाङ्मनसे ॥ इति दधिपयआदीनि ॥ २३ ॥

४। ३१ अर्धर्चाः पुंसि च ८१६ ॥ अर्धर्च गोमय कषाय कार्षापण कुतप कुसप (कुणप) कपाट शङ्ख गूथ यूथ ध्वज कबन्ध पद्म गृह सरक कंस दिवस यूष अन्धकार दण्ड कमण्डलु मण्ड भूत द्वीप द्यूत चक्र धर्म कर्मन् मोदक शतमान यान नख नखर चरण पुच्छ दाडिम हिम रजत सक्तु पिधान सार पात्र घृत सैन्धव औषध आढक चषक द्रोण खलीन पात्रीव षष्टिक वारबाण (वारवारण) प्रोथ कपित्थ [शुष्क] शाल शील शुल्क (शुल्क) शीधु कवच रेणु [ऋण] कपट शीकर मुसल सुवर्ण वर्ण पूर्व चमस क्षीर कर्ष आकाश अष्टापद मङ्गल निधन निर्यास जृम्भ वृत्त पुस्त बुस्त क्ष्वेडित शृङ्ग निगड [खल] मूलक मधु मूल स्थूल शराव नाल वप्र विमान मुख प्रग्रीव शूल वज्र कटक कण्टक [कर्पट] शिखर कल्क [वल्कल] नटमक (नाट मस्तक) वलय कुसुम तृण पङ्क कुण्डल किरीट [कुमुद] अर्बुद अङ्कुश तिमिर आश्रय भूषण इक्कस (इष्वास) मुकुल वसन्त तटाक (तडाग) पिटक विटङ्क विडङ्ग पिण्याक माष कोश फलक दिन दैवत पिनाक समर स्थाणु अनीक उपवास शाक कर्पास [विशाल] चषाल (चखाल) खण्ड दर विटप [रण बल मक] मृणाल हस्त आर्द्र हल [सूत्र] ताण्डव गाण्डीव मण्डप पटह सौध योध पार्श्व शरीर फल [छल] पुर (पुरा) राष्ट्र अम्बर बिम्ब कुट्टिम मण्डल (कुक्कुट) कुडप ककुद खण्डल तोमर तोरण मञ्चक पञ्चक पुङ्ख मध्य [बाल] छाल वल्मीक वर्ष वस्त्र वसु देह उद्यान उद्योग स्नेह स्तेन [स्तन स्वर] संगम निष्क क्षेम शूक क्षत्र पवित्र [यौवन कलह] मालक (पालक) मूषिक [मण्डल वल्कल] कुज (कुञ्ज) विहार लोहित विषाण भवन अरण्य पुलिन दृढ आसन ऐरावत शूर्प तीर्थ लोमन (लोमश) तमाल लोह दण्डक शपथ प्रतिसर दारु धनुस् मान वर्चस्क कूर्च तण्डक मठ सहस्र ओदन प्रवाल शकट अपराह्ण नीड शकल तण्डुल ॥ इत्यर्धर्चादिः ॥ २४ ॥

४। ५९ पैलादिभ्यश्च १०८४ ॥ पैल शालङ्कि सात्यकि सात्यंकामि राहवि रावणि औदञ्चि औदव्रजि औदमेघि औदव्यजि (औदमज्जि) औदभृज्जि दैवस्थानि पैङ्गलोदायनि राहक्षति (राह क्षति) भौलिङ्गि राणि औदन्यि औद्राहमानि औज्जिहानि औदशुद्धि तत्राजाघाणः (तद्राज) ॥ आकृतिगणोऽयम् ॥ इति पैलादयः ॥ २५ ॥

४। ६१ न तौल्वलिभ्यः १०८६ ॥ तौल्वलि धारणि पारणि रावणि दैलीपि दैवति वार्कलि नैवति (नैवाकि) दैवमित्रि (दैवमति) दैवयज्ञि चाफट्टकि वैल्वकि वैकि (वैङ्कि) आनुहारति (आनुराहति) पौष्करसादि आनुरोहति आनुति प्रादोहनि नैमिश्रि प्राडाहनि बान्धकि वैशीति आसिनासि आहिंसि आसुरि नैमिषि आसिबन्धकि पौष्पि कारेणुपालि वैकर्णि वैरकि वैहति ॥ इति तौल्वल्यादिः ॥ २६ ॥

४। ६३ यस्कादिभ्यो गोत्रे ११४६ ॥ यस्क लह्य द्रुह्य अयस्थूण (अयःस्थूण) तृणकर्ण सदामत्त कम्बलहार बहिर्योग कर्णाढक पर्णाढक पिण्डीजङ्घ बकसस्थ (बकसक्थ) विश्रि कुद्रि अजवस्ति मित्रयु रक्षोमुख जङ्घारथ उत्कास कटुक मथक (मन्थक) पुष्करसद् (पुष्करसद्) विषपुट उपरिमेखल क्रोष्टुकमान (क्रोष्टुमान) क्रोष्टुपाद क्रोष्टुमाय शीर्षमाय खरप पदक वर्मुक भलन्दन भडिल भण्डिल भडित भाण्डित ॥ एते यस्कादयः ॥ २७ ॥

४। ६७ न गोपवनादिभ्यः ११४९ ॥ गोपवन शैग्रु (शिग्रु) बिन्दु भाजन अश्वावतान श्यामाक (श्योमाक) श्यामक श्यापर्ण ॥ बिदाद्यन्तर्गणोऽयं गोपवनादिः ॥ २८ ॥

४। ६८ तिककितवादिभ्यो द्वन्द्वे ११५० ॥ तिककितवाः वङ्खरभण्डीरथाः उपकलमकाः पफकनरकाः बकनखगुदपरिणद्धाः उब्जककुभाः लङ्कशान्तमुखाः उत्तरशलङ्कटाः कृष्णाजिनकृष्णसुन्दराः भ्रष्टककपिष्ठलाः अग्निवेशदशेरुकाः ॥ एते तिककितवादयः ॥ २९ ॥

४। ६९ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ११५१ ॥ उपक लमक भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णसुन्दर चूडारक आडारक गडुक उदङ्क सुधायुक अबन्धक पिङ्गलक पिष्ट सुपिष्ट (सपिष्ठ) मयूरकर्ण खरीजङ्घ शलाथल पतञ्जल पदञ्जल कठेरणि कुषीतक कशकृत्स्न (काशकृत्स्न) निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक पर्णक जटिरक बधिरक जन्तुक अनुलोम अनुपद प्रतिलोम अपजग्ध प्रतान अनभिहित कमक वराटक लेखाभ्र कमन्दक पिञ्जूलक वर्णक मसूरकर्ण मदाघ कवन्तक कमन्तक कदामत्त दामकण्ठ। एत उपकादयः ॥ ३० ॥

इति द्वितीयोऽध्यायः।

तृतीयोऽध्यायः।

१। १२ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः २६६७ ॥ भृश शीघ्र चपल मन्द पण्डित उत्सुक सुमनस् दुर्मनस् अभिमनस् उन्मनस् रहस् रोहत् रेहत् संश्चत् तृपत् शश्वत् भ्रमत् वेहत् शुचिस् शुचिवर्चस् अण्डर वर्चस् ओजस् सुरजस् अरजस् ॥ एते भृशादयः ॥ ३१ ॥

१। १३ लोहितादिडाज्भ्यः क्यष् २६६८ ॥ लोहित चरित नील फेन मद्र हरित दास मन्द ॥ लोहितादिराकृतिगणः ॥ ३२ ॥

१ । १८ सुखादिभ्यः कर्तृवेदनायाम् २६७४ ॥ सुख दुःख तृप्त कृच्छ्र अस्र आस्र अलीक प्रतीप करुण कृपण सोढ ॥ इत्येतानि सुखादीनि ॥ ३३ ॥

१ । २७ कण्ड्वादिभ्यो यक् २६७८ ॥ कण्डूञ् मन्तु हणीङ् वल्गु असु [मनस्] महीङ् लाट् लेट् इरस् इरज् इरञ् दुवस् उषस् वेद् मेधा कुषुभ [नमस्] मगध तन्तस् पम्पस् (पपस्) सुख दुःख [भिक्ष चरण चरम अवर] सपर अरर (अरर्) भिषज् भिष्णुज् [अपर आर] इषुध वरण चुरण तुरण भुरण गद्गद एला केला खेला [वेला शेला] लिट् लोट् [लेखा लेख] रेखा द्रवस् तिरस् अगद उरस् तरण (तरिण) पयस् संभूयस् सम्बर ॥ आकृतिगणोऽयम् ॥ इति कण्ड्वादिः ॥ ३४ ॥

१ । १३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः २८९६ ॥ नन्दिवाशिमदिदूषिसाधिव-र्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् । नन्दनः वाशनः मदनः दूषणः साधनः वर्धनः शोभनः रोचनः । सहितपिदमः संज्ञायाम् । सहनः तपनः दमनः जल्पनः रमणः दर्पनः संक्रन्दनः संकर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः विभीषणः लवणः चित्तविनाशनः कुलदमनः [शत्रुदमनः] ॥ इति नन्द्यादिः ॥ ३५ ॥ ग्राही उत्साही उद्दासी उद्भासी स्थायी मन्त्री संमर्दी । रक्षश्रुवपशां नौ । निरक्षी निश्रावी निवापी निशायी । याचृव्याहृव्रजवदवसां प्रतिषिद्धा-नाम् । अयाची अव्याहारी असंव्याहारी अव्राजी अवादी अवासी । अचामचित्तकर्तृकाणाम् । अकारी अहारी अविनायी [विशायी विषायी] विशयी विषयी देशे । विशयी विषयी देशः । अभिभावी भूते । अपराधी उपरोधी परिभवी परिभावी ॥ इति ग्रहादिः ॥ ३६ ॥ पच वच वप वद चल पत नदट् भषट् प्लवट् चरट् गरट् तरट् चोरट् गाहट् सूरट् दवट् [दोषट्] जर (रज) मर (मद) क्षम (क्षप) सेव मेष कोप (कोष) मेध नर्त व्रण दर्श सर्प [दम्भ दर्प] जारभर श्वपच ॥ पचादिराकृतिगणः ॥ ३७ ॥

२ । ९ कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (वा १९९२) ॥ मूलविभुज नखमुच काकगुह कुमुद महीध्र कुध्र गिध्र ॥ आकृतिगणोऽयम् ॥ इति मूलविभुजादयः ॥ ३८ ॥

२ । १९ पार्श्वादिषूपसंख्यानम् (वा १९९९) ॥ पार्श्व उदर पृष्ठ उत्तान अवमूर्धन् ॥ इति पार्श्वादिः ॥ ३९ ॥

३ । ३ भविष्यति गम्यादयः ३१७१ ॥ गमी आगमी भावी प्रस्थायी प्रतिरोधी प्रति-योधी प्रतिबोधी प्रतियायी प्रतियोगी ॥ एते गम्यादयः ॥ ४० ॥

३ । १०४ षिद्भिदादिभ्योऽङ् ३२८१ ॥ भिदा विदारणे । छिदा द्वैधीकरणे । विदा । क्षिपा । गुहा गिर्योषध्योः । श्रद्धा मेधा गोधा । आरा शस्त्र्याम् । हारा । कारा बन्धने । क्षिया । तारा ज्योतिषि । धारा प्रपातने । रेखा चूडा पीडा वपा वसा मृजा । कृपेः संप्रसारणं च । कृपा ॥ इति भिदादिः ॥ ४१ ॥

३ । ९४ संपदादिभ्यः क्विप् (वा २२३३) ॥ संपद् विपद् आपद् प्रतिपद् परिषद् ॥ एते संपदादयः ॥ ४२ ॥

४ । ७४ भीमादयोऽपादाने ३१७३ ॥ भीम भीष्म भयानक वहचर (वह चरु) प्रस्क-

न्दन प्रतपन (प्रपतन) समुद्र स्रुव स्रुक् वृष्टि (दृष्टि) रक्षः संकसुक (शङ्कु सुक) मूलं खलति ॥ आकृतिगणोऽयम् ॥ इति भीमादिः ॥ ४३ ॥

इति तृतीयोऽध्यायः ।

चतुर्थोऽध्यायः ।

१ । ४ अजाद्यतष्टाप् ४९४ । अजा एडका कोकिला चटका अश्वा मूषिका बाला होडा पाका वत्सा मन्दा विलाता पूर्वापिहाणा (पूर्वापहाणा) अपरापहाणा । संभस्त्राजिन-शणपिण्डेभ्यः फलात् । सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् । शूद्रा । क्रुञ्चा उष्णिहा देवविशा ज्येष्ठा कनिष्ठा । मध्यमा पुयोगेऽपि । मूलान्नञः दंष्ट्रा ॥ एतेऽजादयः ॥ ४४ ॥

१ । १० न षट्स्वस्रादिभ्यः ३०८ ॥ स्वसृ दुहितृ ननान्दृ यातृ मातृ तिसृ चतसृ ॥ इति स्वस्रादिः ॥ ४५ ॥

१ । ३९ नित्यं सपत्न्यादिषु ४९२ । समान एक वीर पिण्ड श्व (शिरी) भ्रातृ भद्र पुत्र दासाच्छन्दसि ॥ इति समानादिः ॥ ४६ ॥

१ । ४१ षिद्गौरादिभ्यश्च ४९८ ॥ गौर मत्स्य मनुष्य शृङ्ग पिङ्गल हय गवय मुकय ऋष्य [पुट तूण] द्रुण द्रोण हरिण कोकण (काकण) पटर उणक [आमल] आमलक कुवल बिम्ब बदर फर्करक (कर्कर) तर्कार शर्कार पुष्कर शिखण्ड सलद शष्कण्ड सनन्द सुषम सुषव अलिन्द गडुल षाण्डश आढक आनन्द आश्वत्थ सृपाट आखक (आपचिक) शष्कुल सूर्य (सूर्म) शूर्प सूच यूष (पूष) यूथ सूप मेथ वल्लक धातक सल्लक मालक मालत साल्वक वेतस वृक्ष (वृस) अतस [उभय] भृङ्ग मह मठ छेद पेश मेद श्वन् तक्षन् अनडुही अनड्वाही । एषणः करणे । देह देहल काकादन गवादन तेजन रजन लवण औद्गाहमानि (आद्गाहमानि) गौतम (गोतम) [पारक] अयस्थूण (अयःस्थूण) भौरिकि भौलिकि भौलिङ्गि यान मेध आलम्बि आलजि आलब्धि आलक्षि केवाल आपक आरट नट टोट नोट मूलाट शातन [पोतन] पातन पाठन (पानठ) आस्तरण अधिकरण अधिकार अग्रहायणी (आग्रहायणी) प्रत्यवरोहिणी [सेचन] सुमङ्गलात्संज्ञायाम् । अण्डर सुन्दर मण्डल मन्थर मङ्गल पट पिण्ड [षण्ड] उर्द गुर्द शम सूद औड (आर्द्र) हृद (ह्रद) पाण्ड [भाण्डल] भाण्ड [लोहाण्ड] कदर कन्दर कदल तरुण तलुन कल्माष बृहत् महत् [सोम] सौधर्म । रोहिणी नक्षत्रे । रेवती नक्षत्रे । विकल निष्कल पुष्कल । कटाच्छ्रोणिवचने । पिप्पल्यादयश्च । पिप्पली हरितकी (हरीतकी) कोशातकी शमी वरी शरी पृथिवी क्रोष्टु मातामह पितामह ॥ इति गौरादिः ॥ ४७ ॥

१ । ४९ बह्वादिभ्यश्च ५०३ ॥ बहु पद्धति अञ्चति अङ्कति अंहति शकटि (शकति) । शक्तिः शस्त्रे । शारि वारि राति राधि [शाधि] अहि कपि यष्टि मुनि । इतः प्राण्यङ्गात् । कृदिकारादक्तिनः । सर्वतोऽक्तिन्नर्थादित्येके । चण्ड अराल कृपण कमल विकट

१-२-३. 'अजादिषु पाठ इदानींतनः' इति 'पाककर्ण–' (४ । १ । ६४) सूत्रे कैयटः ।

विशाल विशङ्कट भरुज ध्वज चन्द्रभागान्नद्याम् (चन्द्रभागा नद्याम्) कल्याण उदार पुराण अहन् क्रोड नख खुर शिखा बाल शफ गुद ॥ आकृतिगणोऽयम् ॥ तेन । भग गल राग इत्यादि ॥ इति बह्वादयः ॥ ४८ ॥

१ । ७३ शार्ङ्गरवाद्यञो ङीन् ५२७ ॥ शार्ङ्गरव कापटव गौग्गुलव ब्राह्मण वैद गौतम कामण्डलेय ब्राह्मणकृतेय [आनिचेय] आनिधेय आशोकेय वात्स्यायन मौञ्जायन कैकस काप्य (काव्य) शैब्य एहि पर्येहि आश्मरथ्य औदपान अराल चण्डाल वतण्ड भोगवद्गौरिमतोः संज्ञायां घादिषु नित्यं ह्रस्वार्थम् । नृनरयोर्वृद्धिश्च ॥ इति शार्ङ्गरवादिः ॥ ४९ ॥

१ । ८० क्रौड्यादिभ्यश्च १२०० ॥ क्रौडि लाडि व्याडि आपिशलि आपक्षिति चौपयत चैटयत (वैटयत) सैकयत वैल्वयत सौधातकि । सूत युवत्याम् । भोज क्षत्रिये । यौतकि कौटि भौरिकि भौलिकि [शाल्मलि] शालास्थलि कापिष्ठलि गौकक्ष्य ॥ इति क्रौड्यादिः ॥ ५० ॥

१ । ८४ अश्वपत्यादिभ्यश्च १०७४ ॥ अश्वपति [ज्ञानपति] शतपति धनपति गणपति [स्थानपति यज्ञपति] राष्ट्रपति कुलपति गृहपति [पशुपति] धान्यपति धन्वपति [बन्धुपति धर्मपति] सभापति प्राणपति क्षेत्रपति ॥ इत्यश्वपत्यादिः ॥ ५१ ॥

१ । ८६ उत्सादिभ्योऽञ् १०७८ ॥ उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन । बष्कयासे । पृथिवी [धेनु] पङ्क्ति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलुकुण । उदस्थान देशे । पृषदंश भल्लकीय रथन्तर मध्यंदिन बृहत् महत् सत्त्वत् कुरु पञ्चाल इन्द्रावसान उष्णिह् ककुभ् सुवर्ण देव ग्रीष्मादच्छन्दसि ॥ इत्युत्सादिः ॥ ५२ ॥

१ । ९६ बाह्वादिभ्यश्च १०९६ ॥ बाहु उपबाहु उपवाक निवाकु शिवाकु वटाकु उपनिन्द (उपविन्द) वृषली वृकला चूडा बलाका मूषिका कुशला भगला (छगला) ध्रुवका [धुवका] सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अग्निशर्मन् [भद्रशर्मन् सुशर्मन्] कुनामन् [सुनामन्] पञ्चन् सप्तन् अष्टन् । अमितौजसः सलोपश्च । सुधावत् उदञ्चु शिरस् माष शराविन् मरीची क्षेमवृद्धिन् शृङ्खलतोदिन् खरनादिन् नगरमर्दिन् प्राकारमर्दिन् लोमन् अजीगर्त कृष्ण युधिष्ठिर अर्जुन साम्ब गद प्रद्युम्न राम [उदङ्क] । उदकः संज्ञायाम् । संभूयोम्भसोः सलोपश्च ॥ आकृतिगणोऽयम् ॥ तेन । सात्वकिः जाङ्गिः ऐन्दशर्मिः आजधेनविः इत्यादि ॥ इति बाह्वादयः ॥ ९३ ॥

१ । ९८ गोत्रे कुञ्जादिभ्यश्च्फञ् १०९९ ॥ कुञ्ज ब्रध्न शङ्ख भस्मन् गण लोमन् शठ शाक शुण्डा शुभ विपाश् स्कन्द स्कम्भ ॥ इति कुञ्जादिः ॥ ५४ ॥

१ । ९९ नडादिभ्यः फक् ११०१ ॥ नड चर (वर) बक मुञ्ज इतिक इतिश उपक [एक] लमक । शलङ्कु शलङ्कं च । सप्तल वाजप्य तिक । अग्निशर्मन्वृषगणे । प्राण नर सायक दास मित्र द्वीप पिङ्गर पिङ्गल किंकर किङ्कल [कातर] कातल काश्यप (कुश्यप) काश्य काल्य (काव्य) अज अमुष्य (अमुष्म) । कृष्णरणौ ब्राह्मणवासिष्ठे । अमित्र लिगु चित्र कुमार । क्रोष्टु क्रोष्टं च । लोह दुर्ग स्तम्भ शिंशपा अग्र तृण शकट सुमनस् सुमत मिमत ऋच् जलंधर अध्वर युगंधर हंसक दण्डिन् हस्तिन् [पिण्ड] पञ्चाल चमसिन्

सुकृत्य स्थिरक ब्राह्मण चटक बदर अश्वल खरप लङ्क इन्ध अस्त्र कामुक ब्रह्मदत्त उदुम्बर शोण अलोह दण्डप ॥ इति नडादिः ॥ ९५ ॥

१ । १०४ अनृष्यानन्तर्ये बिदादिभ्योऽञ् ११०६ ॥ बिद उर्व कश्यप कुशिक भरद्वाज उपमन्यु किलात कन्दर्प (किंदर्भ) विश्वानर ऋषिषेण (ऋष्टिषेण) ऋतभाग हर्यश्व प्रियक आपस्तम्ब कूचवार शरद्वत् शुनक (शुनकृ) धेनु गोपवन शिग्रु बिन्दु [भोगक] भाजन [शमिक] अश्वावतान श्यामाक श्यामक [श्यावलि] श्यापर्ण हरित किंदास वह्यस्क अर्कजूष (अर्कलूष) बध्योग विष्णु वृद्ध प्रतिबोध रचित रथीतर (रथन्तर) गविष्ठिर निषाद [शबर अलस] मठर [मृडाकु] सृपाकु मृदु पुनर्भू पुत्र दुहितृ ननान्दृ । परस्त्री परशुं च ॥ इति बिदादिः ॥ ९६ ॥

१ । १०५ गर्गादिभ्यो यञ् ११०७ ॥ गर्ग वत्स । वाजासे । संकृति अज व्याघ्रपात् विदभृत् प्राचीनयोग [अगस्ति] पुलस्ति चमस रेभ अग्निवेश शङ्ख शट शक एक धूम अवट मनस् धनंजय वृक्ष विश्वावसु जरमाण लोहित शंसित बभ्रु वल्गु मण्डु गण्डु शङ्कु लिगु गुहलु मन्तु मङ्क्षु अलिगु जिगीषु मनु तन्तु मनायी सूनु कथक कन्थक ऋक्ष तृक्ष (वृक्ष) [तनु] तरुक्ष तलुक्ष तण्ड वतण्ड कपिकत (कपि कत) कुरुकत अनडुह् कण्व शकल गोकक्ष अगस्त्य कण्डिनी यज्ञवल्क पर्णवल्क अभयजात विरोहित वृषगण रहूगण शाण्डिल वर्णक (चणक) चुलुक मुद्गल मुसल जमदग्नि पराशर जतूकर्ण (जातूकर्ण) महित मन्त्रित अश्मरथ शर्कराक्ष पूतिमाष स्थूरा अदरक (अररक) एलाक पिङ्गल कृष्ण गोलन्द उलूक तितिक्ष भिषज (भिषज्) [भिष्णज] भडित भण्डित दल्भ चेकित चिकित्सित देवहू इन्द्रहू एकलू पिप्पलू बृहदग्नि [सुलोहिन्] सुलाभिन् उक्थ कुटीगु ॥ इति गर्गादिः ॥ ९७ ॥

१ । ११० अश्वादिभ्यः फञ् १११३ । अश्व अश्मन् शङ्ख शूद्रक विद पुट रोहिण खर्जूर (खजूर) [खञ्जार वस्त] पिजूल भडिल भण्डिल भडित भण्डित [प्रकृत रामोद] क्षान्त [काश तीक्ष्ण गोलाङ्क अर्क स्वर स्फुट चक्र श्रविष्ठ] पविन्द पवित्र गोमिन् श्याम धूम धूम्र वाग्मिन् विश्वानर कुट । शप आत्रेये । जन जड खड ग्रीष्म अर्ह कित विशंप विशाल गिरि चपल चुप दासक वैल्य (वैल्व) प्राच्य [धर्म्य] आनडुह्य । पुंसि जाते । अर्जुन [प्रहृत] सुमनस् दुर्मनस् मन (मनस्) [प्रान्त] ध्वन । आत्रेय भरद्वाजे । भरद्वाज आत्रेये । उत्स आतव कितव [वद धन्य पाद] शिव खदिर ॥ इत्यश्वादिः ॥ ९८ ॥

१ । ११२ शिवादिभ्योऽण् १११५ । शिव प्रोष्ठ प्रोष्ठिक चण्ड जम्भ भूरि दण्ड कुठार ककुभ् (ककुभा) अनभिम्लान कोहित सुख संधि मुनि ककुत्स्थ कहोड कोहड कहूय कहय रोध कपिञ्जल (कुपिञ्जल) खञ्जन वतण्ड तृणकर्ण क्षीरहृद जलहृद परिल [पथिक] पिष्ट हैहय [पार्षिका] गोपिका कपिलिका जटिलिका बधिरिका मञ्जीरक [मजिरक] वृष्णिक खञ्जार खञ्जाल [कर्मार] रेख लेख आलेखन विश्रवण रवण वर्तनाक्ष ग्रीवाक्ष [विटप पिटक] पिटाक तृक्षाक नभाक ऊर्णनाभ जरत्कारु [पृथा उत्क्षेप] पुरोहितिका सुरोहितिका सुरोहिका आर्यश्वेत (अर्यश्वेत) सुपिष्ट मसुरकर्ण मयूरकर्ण [खर्जुरकर्ण] कदूरक तक्षन् ऋष्टिषेण गङ्गा विपाश यस्क लह्य द्रुह्य अयस्थूण तृणकर्ण (तृण कर्ण)

पर्ण भलन्दन विरूपाक्ष भूमि इला सपत्नी । द्व्यचो नद्याः । त्रिवेणी त्रिवणं च ॥ इति शिवादिः ॥ आकृतिगणः ॥ ५९ ॥

१ । १२३ शुभ्रादिभ्यश्च ११२६ ॥ शुभ्र विष्टपुर (विठपुर) ब्रह्मकृत शतद्वार शलाथल शलाकाभ्रू लेखाभ्रू (लेखाभ्र) विकंसा (विकास) रोहिणी रुक्मिणी धर्मिणी दिश् शालूक अजबस्ति शकंधि विमातृ विधवा शुक विश देवतर शकुनि शुक्र उग्र ज्ञातल (शतल) बन्धकी मृकण्डु विस्रि अतिथि गोदन्त कुशाम्ब मकष्टु शाताहर पवष्टुरिक सुनामन् । लक्ष्मणश्यामयोर्वासिष्ठे । गोधा कृकलास अणीव प्रवाहण भरत (भारत) भरम मृकण्डु कर्पूर इतर अन्यतर आलीढ सुदन्त सुदक्ष सुवक्षस् सुदामन् कद्रु तुद अकशाय कुमारिका कुठारिका किशोरिका अम्बिका जिह्माशिन् परिधि वायुदत्त शकल शलाका खडूर कुबेरिका अशोका गन्धपिङ्गला खडोन्मत्ता अनुदृष्टिन् (अनुदृष्टि) जरतिन् बलीवर्दिन् विप्र बीज जीव श्वन् अश्मन् अश्व अजिर ॥ इति शुभ्रादिः ॥ आकृतिगणः ॥ ६० ॥

१ । १२६ कल्याण्यादीनामिनङ् च ११३१ ॥ कल्याणी सुभगा दुर्भगा बन्धकी अनुदृष्टि अनुसृति (अनुसृष्टि) जरती बलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री ॥ इति कल्याण्यादिः ॥ ६१ ॥

१ । १३६ गृष्ट्यादिभ्यश्च ११४३ ॥ गृष्टि हृष्टि बलि हलि विश्रि कुद्रि अजबस्ति मित्रयु ॥ इति गृष्ट्यादिः ॥ ६२ ॥

१ । १४६ रेवत्यादिभ्यष्ठक् ११६९ ॥ रेवती अश्वपाली मणिपाली द्वारपाली वृकवञ्चिन् वृकबन्धु वृकग्राह कर्णग्राह दण्डग्राह कुक्कुटाक्ष (ककुदाक्ष) [चामरग्राह] ॥ इति रेवत्यादिः ॥ ६३ ॥

१ । १५१ कुर्वादिभ्यो ण्यः ११७५ ॥ कुरु गर्गर मङ्गुष अजमार रथकार वावदूक । सम्राजः क्षत्रिये । कवि मति (निमाति) कापिञ्जलादि वाक् वामरथ पितृमत् इन्द्रलाजी एजि वातकि दामोष्णीषि गणकारि कैशोरि कुट शालाका (शलाका) मुर पुर एरका शुभ्र अभ्र दर्भ केशिनी । वेनाच्छन्दसि । शूर्पणाय श्यावनाय श्यावरथ शावपुत्र सत्यंकार वडभीकार पथिकार मूढ शकन्धु शङ्कु शाक शालिन् शालीन कर्तृ हर्तृ इन पिण्डी । वामरथस्य कण्वादिवत्स्वरवर्जम् ॥ इति कुर्वादिः ॥ ६४ ॥

१ । १५४ तिकादिभ्यः फिञ् ११७८ ॥ तिक कितक (कितव) संज्ञाबालशिख (संज्ञा बाला शिखा) उरश (उरस्) शाव्य सैन्धव यमुन्द रूप्य ग्राम्य नील अमित्र गौकुक्ष्य (गौकक्ष्य) कुरु देवरथ तैतल औरश (औरस) कौरव्य भौरिकि भौलिकि चौपयत चैटयत शीकयत क्षैतयत वाजवत चन्द्रमस् शुभ गङ्गा वरेण्य सुपामन् आरटव (आरद्ध) वह्यका खल्या (खल्यका) वृष लोमक उदञ्च यज्ञ ॥ इति तिकादिः ॥ ६५ ॥

१ । १५८ वाकिनादीनां कुक्च ११८२ ॥ वाकिन गौधेर कार्कष काक लङ्का । चर्मिवर्मिणोर्नलोपश्च ॥ इति वाकिनादिः ॥ ६६ ॥

१ । १७५ कम्बोजाल्लुक् ११९४ ॥ कम्बोज चोल केरल शक यवन ॥ इति कम्बोजादिः ॥ ६७ ॥

१ । १७८ न प्राच्यभर्गादियौधेयादिभ्यः ११९७ ॥ भर्ग करूश केकय कश्मीर साल्व

सुस्थाल उरश (उरस्) कौरव्य ॥ इति भर्गादिः ॥ ६८ ॥ यौधेय शौक्रेय शौभ्रेय ज्यावाणेय धार्तेय (धौर्तेय) धार्तेय त्रिगर्त भरत उशीनर ॥ इति यौधेयादिः ॥ ६९ ॥

२ । ३८ भिक्षादिभ्योऽण् १२४४ ॥ भिक्षा गर्भिणी क्षेत्र करीष अङ्गार (अङ्गार) चर्मिन् (चर्मन्) धर्मिन् सहस्र युवति पदाति पद्धति अथर्वन् दक्षिणा [भूत विषय श्रोत्र] ॥ इति भिक्षादिः ॥ ७० ॥

२ । ४५ खण्डिकादिभ्यश्च १२५४ ॥ खण्डिक वडवा । क्षुद्रकडालवात् (क्षुद्रकमालवात्) सेना संज्ञायाम् । भिक्षुक शुक उलूक श्वन् अहन् युगवरत्रा (युगवरत्र) हलबन्धा (हलबन्ध) ॥ इति खण्डिकादिः ॥ ७१ ॥

२ । ४९ पाशादिभ्यो यः १२५८ ॥ पाश तृण धूम वात अङ्गार [पाटल] पोत गल पिटक पिटाक शकट हल [नट] वन ॥ इति पाशादिः ॥ ७२ ॥

२ । ५१ खलादिभ्य इनिर्वक्तव्यः (वा २७३८) ॥ खलिनी डूकिनी (डाकिनी) कुटुम्बिनी (कुटुम्बिनी) द्रुमिणी अङ्किनी गविनी रथिनी कुण्डलिनी ॥ इति खलादिः ॥ ७३ ॥

२ । ५३ राजन्यादिभ्यो वुञ् १२६२ ॥ राजन्य आनृत बाभ्रव्य शाकङ्कायन दैवयातव (देवयात) [अव्रीड वरत्रा] जालंधरायण [राजायन] तेलु आत्मकामेय अम्बरीषपुत्र वसाति बैल्ववन शैलूष उदुम्बर तीव्र बैल्वज आर्जुनायन संप्रिय दाक्षि ऊर्णनाभ ॥ इति राजन्यादिः ॥ आकृतिगणः ॥ ७४ ॥

२ । ५४ भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ १२६३ ॥ भौरिकी भौलिकी चौपयत चौटयत (चैटयत) काणेय वाणिजक वाणिकाज्य (वालिकाज्य) सैकयत वैकयत ॥ इति भौरिक्यादिः ॥ ७५ ॥ ऐषुकारि सारस्यायन (सारसायन) चान्द्रायण द्व्याक्षायण त्र्याक्षायण औडायन जौलायन खाडायन दासमित्रि दासमित्रायण शौद्रायण दाक्षायण शापण्डायन (शायण्डायन) तार्क्ष्यायण शौभ्रायण सौवीर [सौवीरायण] शपण्ड (शयण्ड) शौण्ड शयाण्डि (शयाण्ड) वैश्वमानव वैश्वधेनव (वैश्वधेनव) नड तुण्डदेव विश्वदेव [सापिण्डि] ॥ इत्यैषुकार्यादिः ॥ ७६ ॥

२ । ६० क्रतूक्थादिसूत्रान्ताट्ठक् १२७० ॥ उक्थ लोकायत न्याय न्यास पुनरुक्त निरुक्त निमित्त द्विपदा ज्योतिष अनुपद अनुकल्प यज्ञ [धर्म] चर्चा क्रमेतर श्लक्ष (श्लक्ष्ण) संहिता पदक्रम संघट (संघट्ट) वृत्ति परिषद् संग्रह गण [गुण] आयुर्वेद (आयुर्वेद) ॥ इत्युक्थादिः ॥ ७७ ॥

२ । ६१ क्रमादिभ्यो वुन् १२७१ ॥ क्रम पद मीमांसा सामन् ॥ इति क्रमादिः ॥ ७८ ॥

२ । ६३ वसन्तादिभ्यष्ठक् १२७३ ॥ वसन्त [ग्रीष्म] वर्षा शरद (शरत्) हेमन्त शिशिर प्रथम गुण चरम अनुगुण अथर्वन् आथर्वण ॥ इति वसन्तादिः ॥ ७९ ॥

२ । ७५ संकलादिभ्यश्च १२८७ ॥ संकल पुष्कल उत्तम उडुप उद्वेप उत्पुट कुम्भ निधान सुदक्ष सुदत्त सुभूत सुपूत सुनेत्र सुमङ्गल सुपिङ्गल सूत सिकत पूतिका (पूतिक) पूलास कूलास पलाश निवेश गवेश (गवेष) गम्भीर इतर आन् अहन् लोमन् वेमन् चरण (वरुण) बहुल सद्योज अभिषिक्त गोभृत् राजभृत् भल्ल मल्ल माल ॥ इति संकलादिः ॥ ८० ॥

२ । ७७ सुवास्त्वादिभ्योऽण् १२८९ ॥ सुवास्तु (सुवस्तु) वर्णु भण्डु खण्डु सेवालिन् कर्पूरिन् शिखण्डिन् गर्त कर्कश शकटीकर्ण कृष्णकर्ण [कर्क] कर्कन्धुमती गोह अहिसक्थ ॥ इति सुवास्त्वादिः ॥ ८१ ॥

२ । ८० वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः १२९२ ॥ अरीहण (अहीरण) द्रुघण द्रुहण भलग (भगल) उलन्द किरण सांपरायण क्रौष्टायन (क्रौष्ट्रायण) औष्ट्रायण त्रैगर्तायन मैत्रायण भास्त्रायण वैमत्तायन (वैमतायन) गौमतायन सौमतायन सौसायन धौमतायन सौमायन ऐन्द्रायण कौद्रायण (कौन्द्रायण) खाडायन शाण्डिल्यायन रायस्पोष विपथ विपाश उद्दण्ड [उदञ्चन] खाण्डवीरण वीरण काशकृत्स्न (कशकृत्स्न) जाम्बवत शिंशपा रैवत (रेवत) बिल्व सुयज्ञ शिरीष बधिर जम्बु खदिर सुशर्मन् (सशर्मन्) दलत् भलन्दन खण्डु कलन (कनल) यज्ञदत्त ॥ इत्यरीहणादिः ॥ ८२ ॥ कृशाश्व अरिष्ट अरिश्म वेश्मन् विशाल लोमश रोमश रोमक लोमक शबल कूट वर्चल सुवर्चल सुकर सूकर प्रातर (प्रतर) सदृश पुरग पुराग सुख धूम अजिन विनत अवनत कुविद्यास (विकुटचास) पराशर अरुस् अयस् मौद्गल्याकर (मौद्गल्य युकर) ॥ इति कृशाश्वादिः ॥ ८३ ॥ ऋश्य (ऋष्य) न्यग्रोध शर निलीन [निवास निवात] निधान निबन्धन (निबन्ध) [विबद्ध] परिगूढ [उपगूढ] असनि सित मत वेश्मन् उत्तराश्मन् अश्मन् स्थूल बाहु खदिर शर्करा अनडुह (अनडुह्) अरडु परिवंश वेणु वीरण खण्ड दण्ड परिवृत्त कर्दम अंशु ॥ इति ऋश्यादिः ॥ ८४ ॥ कुमुद शर्करा न्यग्रोध इक्कट संकट कङ्कट गर्त बीज परिवाप निर्यास शकट कच मधु शिरीष अश्व अश्वत्थ बल्वज यवाष कूप विकङ्कट दशग्राम ॥ इति कुमुदादिः ॥ ८५ ॥ काश पाश अश्वत्थ पलाश पीयूक्षा चरण वास नड वन कर्दम कच्छूल कङ्कट गुहा बिस तृण कर्पूर बर्बर मधुर ग्रह कपित्थ जतु सीपाल ॥ इति काशादिः ॥ ८६ ॥ तृण नड मूल वन पर्ण वर्ण वराण बिल पुल फल अर्जुन अर्ण सुवर्ण बल चरण बुस ॥ इति तृणादिः ॥ ८७ ॥ प्रेक्षा फलका (हलका) बन्धुका ध्रुवका क्षिपका न्यग्रोध इक्कट कङ्कट [संकट] कट कूप बुक पुक पुट मह परिवाप यवाष धुवका गर्त कूपक हिरण्य ॥ इति प्रेक्षादिः ॥ ८८ ॥ अश्मन् यूथ ऊष मीन नद दर्भ वृन्द गुद खण्ड नग शिखा कोट पाम कन्द कान्द कुल गह्व गुड कुण्डल पीन गुह ॥ इत्यश्मादिः ॥ ८९ ॥ सखि अग्निदत्त वायुदत्त सखिदत्त [गोपिल] भल्लपाल (भल्ल पाल) चक्र चक्रवाक छगल अशोक करवीर वासव वीर पूर वज्र कुशीरक शीहर (सीहर) सरक सरस समर समल सुरस रोह तमाल कदल सतल ॥ इति सख्यादिः ॥ ९० ॥ संकाश कपिल कश्मीर [समीर] सूरसेन सरक सूर । सुपन्थिन्पन्थ च । यूप (यूथ) ॰ [अंश] अङ्ग नासा पलित अनुनाश अश्मन् कूट मलिन दश कुम्भ शीर्ष चिरन्त (विरत) समल सीर पञ्जर पन्थ नल रोमन् लोमन् पुलिन सुपरि कटिप सकर्णक वृष्टि तीर्थ अगस्ति विकर नासिका ॥ इति संकाशादिः ॥ ९१ ॥ बल चुल नल दल वट लकुल उरल पुल (पुल) मूल उलडुल (उल डुल) वन कुल ॥ इति बलादिः ॥ ९२ ॥ पक्ष तुक्ष तुष कुण्ड अण्ड कम्बलिका वलिक चित्र अस्ति । पथिन्पन्थ च ।

कुम्भ सीरक सरक सकल सरस समल अतिश्वन् रोमन् लोमन् हस्तिन् मकर लोमक शीर्ष निवात पाक सहक (सिंहक) अङ्कुश सुवर्णक हंसक हिंसक कुत्स त्रिल खिल यमल हस्त कला सकर्णक ॥ इति पक्षादिः ॥ ९३ ॥ कर्ण वसिष्ठ अर्क अर्कलूष द्रुपद आनडुह्य पाञ्चजन्य स्फिग (स्फिज्) कुम्भी कुन्ती जित्वन् जीवन्त कुलिश आण्डीवत् (आण्डीवत) जव जैत्र आकन (आनक) ॥ इति कर्णादिः ॥ ९४ ॥ सुतंगम मुनिचित विप्रचित्त महाचित्त महापुत्र स्वन श्वेत गाडिक (खडिक) शुक्र विग्र बीजवापिन् (बीजवापिन्) अर्जुन श्वन् अजिर जीव खण्डिन कर्ण विग्रह ॥ इति सुतंगमादिः ॥ ९५ ॥ प्रगदिन् मगदिन् मददिन् कविल खण्डित गदित चूडार मडार मन्दार कोविदार ॥ इति प्रगद्यादिः ॥ ९६ ॥ वराह पलाशा (पलाश) शेरीष (शिरीष) पिनद्ध निबद्ध बलाह स्थूल विदग्ध [विजग्ध] विभग्न [निमग्न] बाहु खदिर शर्करा ॥ इति वराहादिः ॥ ९७ ॥ कुमुद गोमथ रथकार दशग्राम अश्वत्थ शाल्मलि [शिरीष] मुनिस्थल कुण्डल कूट मधुकर्ण घासकुन्द शुचिकर्ण ॥ इति कुमुदादिः ॥ ९८ ॥

२ । ८२ वरणादिभ्यश्च १३०१ ॥ वरणा शृङ्गी शाल्मलि शुण्डी शयाण्डी पर्णी ताम्रपर्णी गोद आलिङ्ग्यायन जालपदी (जानपदी) जम्बू पुष्कर चम्पा पम्पा वल्गु उज्जयनी गया मथुरा तक्षशिला उरसा गोमती वलभी ॥ इति वरणादिः ॥ ९९ ॥

२ । ८६ मध्वादिभ्यश्च १३०५ ॥ मधु बिस स्थाणु वेणु कर्कन्धु शमी करीर हिम किशरा शर्याण मरुत् वार्दाली शर इष्टका आसुति शक्ति आसन्दी शकल शलाका आमिषी इक्षु रोमन् रुष्टि रुष्य तक्षशिला खड वट वेट ॥ इति मध्वादिः ॥ १०० ॥

२ । ९० उत्करादिभ्यश्छः १३०९ ॥ उत्कर संफल शफर पिप्पल पिप्पलीमूल अश्मन् सुवर्ण खलाजिन तिक कितव अणक त्रैवण पिचुक अश्वत्थ काश क्षुद्र भस्त्रा शाल जन्या अजिर चर्मन् उत्क्रोश क्षान्त खदिर शूर्पणाय श्यावनाय नैवाकव तृण वृक्ष शाक पलाश विजिगीषा अनेक आतप फल संपर अर्क गर्त अग्नि वैराणक इडा अरण्य निशान्त पर्ण नीचायक शंकर अवरोहित क्षार विशाल वेत्र अरीहण खण्ड वातागर मन्त्रणार्ह इन्द्रवृक्ष नितान्तवृक्ष (नितान्तावृक्ष) आर्द्रवृक्ष ॥ इत्युत्करादिः ॥ १०१ ॥

२ । ९१ नडादीनां कुक्च १३१० ॥ नड प्लक्ष बिल्व वेणु वेत्र वेतस इक्षु काष्ठ कपोत तृण । क्रुञ्चा ह्रस्वत्वं च । तक्षन्नलोपश्च ॥ इति नडादिः ॥ १०२ ॥

२ । ९५ कत्त्र्यादिभ्यो ढकञ् १३१५ ॥ कत्त्रि उम्भि पुष्कर पुष्कल मोदन कुम्भी कुण्डिन नगरी माहिष्मती वर्मती उख्या ग्राम । कुड्याया यलोपश्च ॥ इति कत्त्र्यादिः ॥ १०३ ॥

२ । ९७ नद्यादिभ्यो ढक् १३१७ ॥ नदी मही वाराणसी श्रावस्ती कौशाम्बी वनकौशाम्बी (वनकोशाम्बी) काशपरी काशफारी (काशफरी) खादिरी पूर्वनगरी पाठा माया शाल्वा दार्वा सेतकी । वडवाया वृषे ॥ इति नद्यादिः ॥ १०४ ॥

२ । ११० प्रस्थोत्तरपदपलद्यादिकोपधादण् १३३१ ॥ पलदी परिषद् रोमक वाहीक कलकीट बहुकीट जालकीट कमलकीट कमलकीकर कमलभिदा गौष्ठी नैकती परिखा शूरसेन गोमती पटच्चर उदपान यकृल्लोम ॥ इति पलद्यादिः ॥ १०५ ॥

२ । ११६ काश्यादिभ्यष्ठञ्ञिठौ १३५० ॥ काशि चेदि (वेदि) सांयाति संवाह

अच्युत मोदमान शकुलाद हास्तिकर्षू कुनामन् हिरण्य करण गोवासन भारङ्गी अरिंदम अरित्र देवदत्त दशग्राम शौवावतान युवराज उपराज देवराज मोदन सिन्धुमित्र दासमित्र सुधामित्र सोमामित्र छागमित्र साधमित्र (सधमित्र) आपदादिपूर्वपदात्कालान्तात् । आपद ऊर्ध्व तत् ॥ इति काश्यादिः ॥ १०६ ॥

२ । १२७ धूमादिभ्यश्च १३५१ ॥ धूम षडण्ड शशादन अर्जुनाव माहकस्थली आनकस्थली माहिषस्थली मानस्थली अट्टस्थली मद्रकस्थली समुद्रस्थली दाण्डायनस्थली राजस्थली विदेह राजगृह सात्रासाह शष्प मित्रवर्ध्र (मित्रवर्ध) भक्षाली मद्रकूल आर्जाकूल द्व्याहव (द्व्याहाव) त्र्यहव (त्र्याहाव) संस्फीय बर्बर वर्ज्य गर्त आनत माठर पाथेय घोष पल्ली आराज्ञी धार्तराज्ञी आवय तीर्थ । कूलात्सौवीरेषु । समुद्रान्नावि मनुष्ये च । कुक्षि अन्तरीय द्वीप अरुण उज्जयनी पट्टार दक्षिणापथ साकेत ॥ इति धूमादिः ॥ १०७ ॥

२ । १३३ कच्छादिभ्यश्च १३५७ ॥ कच्छ सिन्धु वर्णु गन्धार मधुमत् कम्बोज कश्मीर साल्व कुरु अनुषण्ड द्वीप अनूप अजवाह विजापक कलूतर रङ्कु ॥ इति कच्छादिः ॥ १०८ ॥

२ । १३८ गहादिभ्यश्च १३६२ ॥ गह अन्तस्थ सम विषम । मध्य मध्यमं चाण्चरणे । उत्तम अङ्ग वङ्ग मगध पूर्वपक्ष अपरपक्ष अधमशाख उत्तमशाख एकशाख समानशाख समानग्राम एकग्राम एकवृक्ष एकपलाश इष्वग्र इष्वनीक अवस्यन्दन कामप्रस्थ शाडिकाडायनि (खाडायन) काठेरणि लावेरणि सौमित्रि शैशिरि आसुत् दैवशर्मि श्रौति आहिंसि आमित्रि व्याडि वैजि आध्यश्वि आनृशसि (आनृशंसि) शौङ्गि आग्निशर्मि भौजि वाराटकि वाल्मिकि (वाल्मीकि) क्षैमवृद्धि आश्वत्थि औद्गाहमानि ऐकबिन्दवि दन्ताग्र हंस तत्त्वग्र (तन्त्वग्र) उत्तर अन्तर (अनन्तर) । मुखपार्श्वतसोर्लोपः । जनपरयोः कुक्च । देवस्य च । वेणुकादिभ्यश्छण् ॥ इति गहादिः ॥ आकृतिगणः ॥ १०९ ॥

३ । १६ संधिवेलाद्यृतुनक्षत्रेभ्योऽण् १३८७ ॥ संधिवेला संध्या अमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी प्रतिपत् । संवत्सरात्फलपर्वणोः ॥ इति संधिवेलादिः ॥ ११० ॥

३ । ५४ दिगादिभ्यो यत् १४२९ ॥ दिश् वर्ग पूग गण पक्ष धाय्य मित्र मेधा अन्तर पथिन् रहस् अलीक उखा साक्षिन् देश आदि अन्त मुख जघन मेघ यूथ । उदकात्संज्ञायाम् । न्याय (न्याय) वंश वेश काल आकाश ॥ इति दिगादिः ॥ १११ ॥

३ । ५९ परिमुखादिभ्यश्च (वा २८६९) ॥ परिमुख परिहनु पर्योष्ठ पर्युलूखल परिसीर उपसीर उपस्थूण उपकलाप अनुपथ अनुपद अनुगङ्ग अनुतिल अनुसीत अनुसाय अनुसीर अनुमाष अनुयव अनुयूप अनुवंश प्रतिशाख ॥ इति परिमुखादिः ॥ ११२ ॥

३ । ६० अध्यात्मादिभ्यश्च (वा २८७२) ॥ अध्यात्म अधिदेव अधिभूत ॥ इत्यध्यात्मादिः ॥ ११३ ॥

३ । ७३ ऋगयनादिभ्यः १४५२ ॥ ऋगयन पदव्याख्यान छन्दोमान छन्दोभाषा छन्दोविचिति न्याय पुनरुक्त निरुक्त व्याकरण निगम वास्तुविद्या क्षत्रविद्या अङ्गविद्या विद्या उत्पात उत्पाद उद्याव संवत्सर मुहूर्त उपनिषद् निमित्त शिक्षा भिक्षा ॥ इत्यृगयनादिः ॥ ११४ ॥

३ । ७६ शुण्डिकादिभ्योऽण् १४५९ ॥ शुण्डिक कृकण स्थण्डिल उदपान उपल तीर्थ भूमि तृण पर्ण ॥ इति शुण्डिकादिः ॥ ११५ ॥

३ । ९२ शण्डिकादिभ्यो ञ्यः १४७२ ॥ शण्डिक सर्वसेन सर्वकेश शक शट रक शङ्ख बोध ॥ इति शण्डिकादिः ॥ ११६ ॥

३ । ९३ सिन्धुतक्षशिलादिभ्योऽणञौ १४७३ ॥ सिन्धु वर्णु मधुमत् कम्बोज साल्व कश्मीर गन्धार किष्किन्धा उरसा दरद (दरद्) गान्दिका ॥ इति सिन्ध्वादिः ॥ ११७ ॥ तक्षशिला वत्सोद्धरण कैमेदुर ग्रामणी छगल क्रोष्टुकर्ण सिंहकर्ण संकुचित किंनर काण्डधार पर्वत अवसान बर्बर कंस ॥ इति तक्षशिलादिः ॥ ११८ ॥

३ । १०६ शौनकादिभ्यश्छन्दसि १४८६ ॥ शौनक वाजसनेय शार्ङ्गरव शापेय शाष्पेय खाडायन स्तम्भ स्कन्ध देवदर्शन रज्जुभार रज्जुकण्ठ कठशाठ कषाय तल दण्ड पुरुषांसक [अश्वपेज] ॥ इति शौनकादिः ॥ ११९ ॥

३ । ११८ कुलालादिभ्यो वुञ् १४९८ ॥ कुलाल वरुड चण्डाल निषाद कर्मार सेना सिरिन्ध्र (सिरिध्र) सैरिन्ध्र देवराज पर्षत् (परिषत्) वधू मधु रुरु रुद्र अनडुह (अनडुह्) ब्रह्मन् कुम्भकार श्वपाक ॥ इति कुलालादिः ॥ १२० ॥

३ । १३१ रैवतिकादिभ्यश्छः १५११ ॥ रैवतिक स्वापिशि क्षैमवृद्धि गौरग्रीव (गौरग्रीवि) औदमेघि औदवापि बैजवापि ॥ इति रैवतिकादिः ॥ १२१ ॥

३ । १३६ बिल्वादिभ्योऽण् १५१६ ॥ बिल्व व्रीहि काण्ड मुद्ग मसूर गोधूम इक्षु वेणु गवेधुका कर्पासी पाटली कर्कन्धु कुटीर ॥ इति बिल्वादिः ॥ १२२ ॥

३ । १४१ पलाशादिभ्यो वा १५२१ ॥ पलाश खदिर शिंशपा स्पन्दन पूलाक करीर शिरीष यवास विकङ्कत ॥ इति पलाशादिः ॥ १२३ ॥

३ । १४४ नित्यं वृद्धशरादिभ्यः १५२४ ॥ शर दर्भ मृद् (मृत्) कुटी तृण सोम वल्वज ॥ इति शरादिः ॥ १२४ ॥

३ । १५२ तालादिभ्योऽण् १५३० ॥ तालाद्धनुषि । बार्हिण इन्द्रालिश (इन्द्रासिष) इन्द्रादृश इन्द्रायुध चय श्यामाक पीयूक्षा ॥ इति तालादिः ॥ १२५ ॥

३ । १५४ प्राणिरजतादिभ्योऽञ् १५३२ ॥ रजत सीस लोह उदुम्बर नीप दारु रोहीतक विभीतक पीतदारु तीव्रदारु त्रिकण्टक कण्टकार ॥ इति रजतादिः ॥ १२६ ॥

३ । १६४ प्लक्षादिभ्योऽण् १५४२ ॥ प्लक्ष न्यग्रोध अश्वत्थ इङ्गुदी शिग्रु [रुरु] ककुभ बृहती ॥ इति प्लक्षादिः ॥ १२७ ॥

३ । १६७ हरीतक्यादिभ्यश्च १५४६ ॥ हरीतकी कोशातकी नखरजनी शष्कण्डी दाडी दोडी श्वेतपाकी अर्जुनपाकी द्राक्षा काला ध्वाक्षा गभीका कण्टकारिका पिप्पली चिम्पा (चिञ्चा) शेफालिका ॥ इति हरीतक्यादिः ॥ १२८ ॥

४ । १ माशब्दादिभ्य उपसंख्यानम् (वा २९९५) ॥ माशब्दः । नित्यशब्दः । कार्यशब्दः ॥ इति माशब्दादिः ॥ १२९ ॥

४ । १ आहौ प्रभूतमादिभ्यः (वा २९९६) ॥ प्रभूत पर्याप्त ॥ इति प्रभूतादिः ॥ १३० ॥

४ । १ पृच्छतौ सुस्नातादिभ्यः (वा २९९७) ॥ सुस्नात सुखरात्रि सुखशयन ॥ इति सुस्नातादिः ॥ १३१ ॥

४ । १ गच्छतौ परदारादिभ्यः (वा २९९८) ॥ परदार गुरुतल्प ॥ इति परदारादिः ॥ १३२ ॥

४ । १० पर्पादिभ्यः ष्ठन् १५५८ ॥ पर्प अश्व अश्वत्थ रथ जाल न्यास व्याल । पादः पञ्च ॥ इति पर्पादिः ॥ १३३ ॥

४ । १२ वेतनादिभ्यो जीवति १५६२ ॥ वेतन वाहन अर्धवाहन धनुर्दण्ड जाल वेश उपवेश प्रेषण उपवस्ति सुख शय्या शक्ति उपनिषद् उपदेश स्फिज् (स्फिज) पाद [उपस्थ] उपस्थान उपहस्त ॥ इति वेतनादिः ॥ १३४ ॥

४ । १५ हरत्युत्सङ्गादिभ्यः १५६५ ॥ उत्सङ्ग [उडुप] उत्पुत [उत्पन्न] उत्पुट पिटक पिटाक ॥ इत्युत्सङ्गादिः ॥ १३५ ॥

४ । १६ भस्त्रादिभ्यः ष्ठन् १५६६ ॥ भस्त्रा भरट भरण शीर्षभार शीर्षेभार अंसभार अंसेभार ॥ इति भस्त्रादिः ॥ १३६ ॥

४ । १९ निर्वृत्तेऽक्षद्यूतादिभ्यः १५६९ ॥ अक्षद्यूत [जानुप्रहृत] जङ्घाप्रहृत जङ्घाप्रहृत पादस्वेदन कण्टकमर्दन गतानुगत गतागत यातोपयात अनुगत ॥ इत्यक्षद्यूतादिः ॥ १३७ ॥

४ । ४८ अण्महिष्यादिभ्यः १५९८ ॥ महिषी प्रजापति प्रजावती प्रलेपिका विलेपिका अनुलेपिका पुरोहित मणिपाली अनुवारक [अनुचारक] होतृ यजमान ॥ इति महिष्यादिः ॥ १३८ ॥

४ । ५३ किसरादिभ्यः ष्ठन् १६०३ ॥ किसर नरद नलद स्थागल तगर गुग्गुलु उशीर हरिद्रा हरिद्रु पर्गी (पर्णी) ॥ इति किसरादिः ॥ १३९ ॥

४ । ६२ छत्रादिभ्यो णः १६१२ ॥ छत्र शिक्षा प्ररोह स्था बुभुक्षा चुरा तितिक्षा उपस्थान कृषि कर्मन् विश्वधा तपस् सत्य अनृत विशिखा विशिका भक्षा उदस्थान पुरोडा विक्षा चुक्षा मन्द्र ॥ इति छत्रादिः ॥ १४० ॥

४ । ९९ प्रतिजनादिभ्यः खञ् १६९१ ॥ प्रतिजन इदंयुग संयुग समयुग परयुग परकुल परस्यकुल अमुष्यकुल सर्वजन विश्वजन महाजन पञ्चजन ॥ इति प्रतिजनादिः ॥ १४१ ॥

४ । १०२ कथादिभ्यष्ठक् १६९४ ॥ कथा विकथा विश्वकथा संकथा वितण्डा कुष्टविद् (कुष्टविद्) जनवाद जनेवाद जनोवाद वृत्ति संग्रह गुण गण आयुर्वेद ॥ इति कथादिः ॥ १४२ ॥

४ । १०३ गुडादिभ्यष्ठञ् १६९५ ॥ गुड कुल्माष सक्तु अपूप मांसौदन इक्षु वेणु संग्राम संघात [संक्राम संवाह] प्रवास निवास उपवास ॥ इति गुडादिः ॥ १४३ ॥

इति चतुर्थोऽध्यायः ।

पञ्चमोऽध्यायः ।

१ । २ उगवादिभ्यो यत् १६६२ ॥ गो हविस् अक्षर विष बर्हिस् अष्टका स्खदा युग मेधा स्रुच् । नाभि नभं च । शुनः संप्रसारणं वा च दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम् । ऊधसोऽनङ् । कूप खद दर खर असुर अध्वन् (अध्वन) क्षर वेद बीज दीस (दीप्त) ॥ इति गवादिः ॥ १४४ ॥

१ । ४ विभाषा हविरपूपादिभ्यः १६६४ ॥ अपूप तण्डुल अभ्युष (अभ्यूष) [अभ्योष अवोष अभ्येष] पृथुक ओदन सूप पूप किण्व प्रदीप मुसल कटक कर्णवेष्टक [इर्गल] अर्गल । अन्नविकारेभ्यश्च । यूप स्थूणा दीप अश्व पत्र ॥ इत्यपूपादिः ॥ १४५ ॥

१ । २० असमासे निष्कादिभ्यः १६८२ ॥ निष्क पण पाद माष वाह द्रोण षष्टि ॥ इति निष्कादिः ॥ १४६ ॥

१ । ३९ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् १७०९ ॥ अश्व अश्मन् गण ऊर्णा (उर्म) उमा भङ्गा (गङ्गा) वर्षा वसु ॥ इत्यश्वादिः ॥ १४७ ॥

१ । ५० तद्धरति वहत्यावहति भाराद्वंशादिभ्यः १७१६ ॥ वंश कुटज वल्वज मूल स्थूणा (स्थूण) अक्ष अश्मन् अश्व श्लक्ष्ण इक्षु खट्वा ॥ इति वंशादिः ॥ १४८ ॥

१ । ६४ छेदादिभ्यो नित्यम् १७२९ ॥ छेद भेद द्रोह दोह नर्ति (नर्त) कर्ष [तीर्थ] संप्रयोग विप्रयोग प्रयोग [विप्रकर्ष] प्रेषण संप्रश्न विप्रश्न विकर्ष प्रकर्ष । विराग विरङ्गं च ॥ इति छेदादिः ॥ १४९ ॥

१ । ६६ दण्डादिभ्यो यः १७३१ ॥ दण्ड मुसल मधुपर्क कशा अर्घ मेघ मेधा सुवर्ण उदक वध युग गुहा भाग इभ भङ्ग ॥ इति दण्डादिः ॥ १५० ॥

१ । ९४ महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् (वा ३०६७) ॥ महानाम्नी आदित्यव्रत गोदान ॥ इति महानाम्न्यादिः ॥ १५१ ॥

१ । ९४ अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः (वा ३०६९) ॥ अवान्तरदीक्षा तिलव्रत देवव्रत ॥ इत्यवान्तरदीक्षादिः ॥ १५२ ॥

१ । ९७ व्युष्टादिभ्योऽण् १७६१ ॥ व्युष्ट नित्य निष्क्रमण प्रवेशन [उपसंक्रमण] तीर्थ [अस्तरण] सङ्ग्राम संघात ॥ इति व्युष्टादिः ॥ १५३ ॥ अग्निपदादिभ्य उपसंख्यानम् (वा ३०७५) ॥ अग्निपद पीलुमूल (पीलू मूल) प्रवास उपवास ॥ इत्यग्निपदादिः आकृतिगणः ॥ १५४ ॥

१ । १०१ तस्मै प्रभवति संतापादिभ्यः १७६५ ॥ संताप संनाह सङ्ग्राम संयोग संपराय [संवेशन] संपेष निष्पेष [सर्ग] निसर्ग विसर्ग उपसर्ग प्रवास उपवास संघात संवेष संवास संमोदन [सक्तु] मांसौदनाद्विगृहीतादपि ॥ इति संतापादिः ॥ १५५ ॥

१ । १०९ तदप्रकरणे उपवस्त्रादिभ्य उपसंख्यानम् (वा) ॥ उपवस्तृ प्राशितृ चूडा श्रद्धा ॥ इत्युपवस्त्रादिः ॥ १५६ ॥

१ । १११ अनुप्रवचनादिभ्यश्छः १७७४ ॥ अनुप्रवचन उत्थापन उपस्थापन संवेशन प्रवेशन अनुप्रवेशन अनुवासन अनुवचन अनुवाचन अन्वारोहण प्रारम्भण आरम्भण आरोहण ॥ इत्यनुप्रवचनादिः ॥ १५७ ॥

१ । १११ स्वर्गादिभ्यो यद्वक्तव्यः (वा ३०७७) ॥ स्वर्ग यशस् आयुस् काम धन ॥ इति स्वर्गादिः ॥ १५८ ॥

१ । १११ पुण्याहवाचनादिभ्यो लुग्वक्तव्यः (वा ३०७८ ॥ पुण्याहवाचन स्वस्तिवाचन शान्तिवाचन ॥ इति पुण्याहवाचनादिः ॥ १५९ ॥

१ । १२२ पृथ्वादिभ्य इमनिज्वा १७८४ ॥ पृथु मृदु महत् पटु तनु लघु बहु साधु आशु उरु गुरु बहुल खण्ड दण्ड चण्ड अकिंचन बाल होड पाक वत्स मन्द स्वादु ह्रस्व दीर्घ प्रिय वृष ऋजु क्षिप्र क्षुद्र अणु ॥ इति पृथ्वादिः ॥ १६० ॥

१ । १२३ वर्णदृढादिभ्यः ष्यञ्च १७८७ ॥ दृढ वृढ परिवृढ भृश कृश [वक्र] शुक्र चुक्र आम्र [कृष्ट] लवण ताम्र शीत उष्ण जड बधिर पण्डित मधुर मूर्ख मूक । वेर्यातलातमतिर्मनःशारदानाम् । समो मतिमनसोः । जवन ॥ इति दृढादिः ॥ १६१ ॥

१ । १२४ गुणवचनब्राह्मणादिभ्यः कर्मणि च १७८८ ॥ ब्राह्मण वाडव माणव । अर्हतो नुम्च । चोर धूर्त आराधय विराधय अपराधय उपराधय एकभाव द्विभाव त्रिभाव अन्यभाव अक्षेत्रज्ञ संवादिन् संवेशिन् संभाषिन् बहुभाषिन् शीर्षघातिन् विघातिन् समस्थ विषमस्थ परमस्थ मध्यमस्थ अनीश्वर कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ निश्न बालिश अलस दुःपुरुष कापुरुष राजन् गणपति अधिपति गडुल दायाद विशस्ति विषम विपात निपात । सर्ववेदादिभ्यः स्वार्थे । चतुर्वेदस्योभयपदवृद्धिश्च । शौटीर ॥ आकृतिगणोऽयम् ॥ इति ब्राह्मणादिः ॥ १६२ ॥

१ । १२४ चातुर्वर्ण्यादीनामुपसंख्यानम् (वा ३०९४ ॥ चतुर्वर्ण चतुर्वेद चतुराश्रम सर्वविद्य त्रिलोक त्रिस्वर षड्गुण सेना अनन्तर संनिधि समीप उपमा सुख तदर्थ इतिह मणिक ॥ इति चतुर्वर्णादिः ॥ १६३ ॥

१ । १२८ पत्यन्तपुरोहितादिभ्यो यक् १७९३ ॥ पुरोहित । राजासे । ग्रामिक पिण्डिक सुहित बालमन्द (बाल मन्द) खण्डिक दण्डिक वर्मिक कर्मिक धर्मिक शिलिक [सूतिक मूलिक तिलक] अञ्जलिक (अन्तलिक) [रूपिक ऋषिक] पुत्रिक अविक छत्रिक पर्षिक पथिक चर्मिक [प्रतिक] सारथि आस्तिक सूचिक संरक्षसूचक (संरक्ष सूचक) नास्तिक [अजानिक शाक्वर नागर चूडिक] ॥ इति पुरोहितादिः ॥ १६४ ॥

१ । १२९ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् १७१४ ॥ उद्गातृ उन्नेतृ प्रतिहर्तृ प्रशास्तृ होतृ पोतृ हर्तृ रथगणक पत्तिगणक सुष्ठु दुष्ठु अध्वर्यु वधू । सुभग मन्त्रे ॥ इत्युद्गात्रादिः ॥ १६५ ॥

१ । १३० हायनान्तयुवादिभ्योऽण् १७९९ ॥ युवन् स्थविर होतृ यजमान पुरुषासे । भ्रातृ कुतुक श्रमण (श्रणम) कटुक कमण्डलु कुस्त्री सुस्त्री दुःस्त्री सुहृदय दुर्हृदय सुहृद् दुर्हृद् सुभ्रातृ दुर्भ्रातृ वृषल परिव्राजक सब्रह्मचारिन् अनृशंस । हृदयासे कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ । श्रोत्रियस्य यलोपश्च ॥ इति युवादिः ॥ १६६ ॥

१ । १३३ द्वन्द्वमनोज्ञादिभ्यश्च १७९८ ॥ मनोज्ञ प्रियरूप अभिरूप कल्याण मेधाविन् आढ्य कुलपुत्र छान्दस छात्र श्रोत्रिय चोर धूर्त विश्वदेव युवन् कुपुत्र ग्रामपुत्र ग्राम-

कुलाल ग्रामड (ग्रामषण्ड) ग्रामकुमार सुकुमार बहुल [अवश्यपुत्र] अमुष्यपुत्र अमुष्यकुल सारपुत्र शतपुत्र ॥ इति मनोज्ञादिः ॥ १६७ ॥

२ । २४ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ १८२९ ॥ पीलु कर्कन्धू (कर्कन्धु) शमी करीर बल (कुवल) बदर अश्वत्थ खदिर ॥ इति पील्वादिः ॥ १६८ ॥ कर्ण अक्षि नख मुख केश पाद गुल्फ भ्रू शृङ्ग दन्त ओष्ठ पृष्ठ ॥ इति कर्णादिः ॥ १६९ ॥

२ । ३६ तदस्य संजातं तारकादिभ्य इतच् १८३७ ॥ तारका पुष्प कर्णक मञ्जरी ऋजीष [क्षण सूच] मूत्र निष्क्रमण पुरीष उच्चार प्रचार [विचार] कुड्मल कण्टक मुसल [मुकुल] कुसुम कुतूहल स्तबक (स्तवक) किसलय पल्लव [खण्ड] वेग निद्रा मुद्रा बुभुक्षा [धेनुष्या] पिपासा श्रद्धा अभ्र पुलक अङ्गारक वर्णक द्रोह दोह सुख दुःख उत्कण्ठा भर व्याधि वर्मन् व्रण गौरव शास्त्र तरङ्ग तिलक चन्द्रक अन्धकार गर्व कुमुर (मुकुर) हर्ष उत्कर्ष [रण] कुवलय गर्ध क्षुध् सीमन्त ज्वर गर रोग रोमाञ्च पण्डा कज्जल तृष् कोरक कल्लोल स्थपुट फल कञ्चुक शृङ्गार अङ्कुर शैवल बकुल श्वभ्र आराल कलङ्क कर्दम [कन्दल] मूर्च्छा अङ्गार हस्तक प्रतिबिम्ब विघ्नतन्त्र प्रत्यय दीक्षा गर्ज । गर्भादप्राणिनि ॥ इति तारकादिः ॥ आकृतिगणः ॥ १७० ॥

२ । ६१ विमुक्तादिभ्योऽण् १८६१ ॥ विमुक्त देवासुर रक्षोसुर उपसद् सुवर्ण परिसारक [सदसत्] वसु मरुत् पत्नीवत् वसुमत् महीयत्व सत्त्वत् बर्हवत् दशार्ण दशार्ह वयस् हविर्धान पतत्रिन् महित्री अस्यहत्य सोमापुषन् (सोमापूषन्) इडा अग्नाविष्णु उर्वशी वृत्रहन् ॥ इति विमुक्तादिः ॥ १७१ ॥

२ । ६२ गोषदादिभ्यो वुन् १८६२ ॥ गोषद (गोषद्) इषेत्वा मातरिश्वन् देवस्यत्वा देवीरापः कृष्णोऽस्याखरेष्ठः देवींधिया (देवींधिय) रक्षोहण युञ्जान अञ्जन प्रभूत प्रतूर्त कृशानु (कृशाकु) ॥ इति गोषदादिः ॥ १७२ ॥

२ । ६४ आकर्षादिभ्यः कन् १८६४ ॥ आकर्ष त्सरु पिशाच पिचण्ड अशनि अश्मन् निचय चय [विजय] जय आचय नय पाद दीप ह्रद ह्राद ह्लाद [गद्गद] शकुनि ॥ इत्याकर्षादिः ॥ १७३ ॥

२ । ८८ इष्टादिभ्यश्च १८८८ ॥ इष्ट पूर्त उपासादित निगदित परिगदित [परिवादित] निकथित निषादित निपठित संकलित परिकलित संरक्षित परिरक्षित अर्चित गणित अवकीर्ण आयुक्त गृहीत आम्नात श्रुत अधीत [अवधान] आसेवित अवधारित अवकल्पित निराकृत उपकृत उपाकृत अनुयुक्त अनुगणित अनुपठित व्याकुलित ॥ इतीष्टादिः ॥ १७४ ॥

२ । ९५ रसादिभ्यश्च १८९५ ॥ रस रूप वर्ण गन्ध स्पर्श शब्द स्नेह भाव । गुणात् । एकाचः ॥ इति रसादिः ॥ १७५ ॥

२ । ९७ सिध्मादिभ्यश्च १९०४ ॥ सिध्म गडु मणि नाभि बीज [वीणा] कृष्ण निष्पाव पांसु पार्श्व पर्शू हनु सक्तु मास (मांस) । पार्ष्णिधमन्योर्दीर्घश्च । वातदन्तबलललाटानामूङ् च । [जटाघटाकटाकालाः क्षेपे । पर्ण उदक प्रज्ञा सक्थि कर्ण स्नेह शीत श्याम पिङ्ग पित्त पुष्क पृथु] मृदु मञ्जु [मण्ड] पत्र चटु कपि गण्डु ग्रन्थि श्री

कुश धारा वर्ष्मन् पक्ष्मन् श्लेष्मन् पेश निष्पाद् कुण्ड । क्षुद्र जन्तूपतापयोश्च ॥ इति सिध्मादिः ॥ १७६ ॥

२ । १०० लोमादिपामादिपिच्छादिभ्यः शनेलचः १९०७ ॥ लोमन् रोमन् बभ्रु हरि गिरि कर्क कपि मुनि तरु ॥ इति लोमादिः ॥ १७७ ॥ पामन् वामन् वेमन् हेमन् श्लेष्मन् कद्रु (कद्रू) वलि सामन् ऊष्मन् कृमि । अङ्गात्कल्याणे । शाकीपलाली-दद्रूणां ह्रस्वत्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसंधेः । लक्ष्म्या अच्च ॥ इति पामादिः ॥ १७८ ॥ पिच्छा उरस् ध्रुवक ध्रुवक । जटाघटाकालाः क्षेपे । वर्ण उदक पङ्क प्रज्ञा ॥ इति पिच्छादिः ॥ १७९ ॥

२ । १०३ ज्योत्स्नादिभ्य उपसंख्यानम् (वा ३२००) ॥ ज्योत्स्ना तमिस्र कुण्डल कुतप विसर्प विपादिका ॥ इति ज्योत्स्नादिः ॥ १८० ॥

२ । ११६ व्रीह्यादिभ्यश्च १९२३ ॥ व्रीहि माया [शाला] शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्रा संज्ञा वडवा कुमारी नौ वीणा बलाका यवखदनौ कुमारी । शीर्षान्नञः ॥ इति व्रीह्यादिः ॥ १८१ ॥

२ । ११७ तुन्दादिभ्य इलच १९२४ ॥ तुन्द उदर पिचण्ड यव व्रीहि । स्वाङ्गाद्विवृद्धौ ॥ इति तुन्दादिः ॥ १८२ ॥

२ । १२७ अर्शआदिभ्योऽच् १९३३ ॥ अर्शस् उरस् तुन्द चतुर पलित जटा [घटा] घाटा अभ्र (अघ) [कर्दम] अम्ल लवण । स्वाङ्गाद्धीनात् । वर्णात् ॥ इत्यर्श-आदिः ॥ आकृतिगणः ॥ १८३ ॥

२ । १३१ सुखादिभ्यश्च १९३७ ॥ सुख दुःख तृप्र कृच्छ्र अस्र (आश्र) आस्र (अस्र) अलीक करुण सोढ प्रतीप शील हल । माला क्षेपे । [कृपण] प्रणाय (प्रणय) दल कक्ष ॥ इति सुखादिः ॥ १८४ ॥

२ । १३५ पुष्करादिभ्यो देशे १९४१ ॥ पुष्कर पद्म उत्पल तमाल कुमुद नड कपित्थ बिस मृणाल कर्दम शालूक विगर्ह करीष शिरीष यवास [प्रवास] हिरण्य कैरव कल्लोल तट तरङ्ग पङ्कज सरोज राजीव नालीक सरोरुह पुटक अरविन्द अम्भोज अब्ज कमल [कह्लोल] पयस् ॥ इति पुष्करादिः ॥ १८५ ॥

२ । १३६ बलादिभ्यो मतुबन्यतरस्याम् १९४२ ॥ बल उत्साह [उद्भास उद्वास] उद्वास शिखा कुल चूडा सुल कूल आयाम व्यायाम उपयाम आरोह अवरोह परिणाह [युद्ध] ॥ इति बलादिः ॥ १८६ ॥

३ । १४ दृशिग्रहणाद्भवदादियोग एव (वा ३२४४) ॥ भवान् दीर्घायुः देवानांप्रियः आयुष्मान् ॥ इति भवदादिः ॥ १८७ ॥

३ । १०० देवपथादिभ्यश्च २०५५ ॥ देवपथ [हंसपथ वारिपथ रथपथ] स्थलपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपथ सिद्धगति उष्ट्रग्रीव वायरज्जु हस्त इन्द्र दण्ड पुष्प मत्स्य ॥ इति देवपथादिः ॥ आकृतिगणः ॥ १८८ ॥

३ । १०३ शाखादिभ्यो यः २०५८ ॥ शाखा मुख जघन शृङ्ग मेघ अभ्र चरण स्कन्ध स्कद (स्कन्द) उरस् शिरस् अग्र शाण ॥ इति शाखादिः ॥ १८९ ॥

३ । १०७ शर्करादिभ्योऽण् २०६२ ॥ शर्करा कपालिका कपाटिका कपिठिका (कनिष्ठिका) पुण्डरीक शतपत्र गोलोमन् लोमन् गोपुच्छ नराची नकुल सिकता ॥ इति शर्करादिः ॥ १९० ॥

३ । १०८ अङ्गुल्यादिभ्यष्ठक् २०६३ ॥ अङ्गुली भरुज बभ्रु वल्गु मण्डर मण्डल शष्कुली हरि कपि मुनि रुह खल उदश्वित् गोणी उरस् कुलिश ॥ इत्यङ्गुल्यादिः ॥ १९१ ॥

३ । ११६ दामन्यादित्रिगर्तषष्ठाच्छः २०६९ ॥ दामनि औलपि बैजवापि औदकि औदङ्कि अच्युतन्ति (आच्युतन्ति) अच्युतदन्ति (आच्युतदन्ति) शाकुन्तकि आकिदन्ति औडवि काकदन्तकि शात्रुंतपि सार्वसेनि बिन्दु बैन्दवि तुलभ मौञ्जायन काकन्दि सावित्रीपुत्र ॥ इति दामन्यादिः ॥ १९२ ॥

३ । ११७ पर्श्वादियौधेयादिभ्योऽणञौ २०७० ॥ पर्शु असुर रक्षस् बाह्लीक वयस् वसु मरुत् सत्वत् दशार्ह पिशाच अशनि कार्षापण ॥ इति पर्श्वादिः ॥ १९३ ॥ यौधेय [कौशेय] शाक्रेय शौभ्रेय धार्तेय घार्तेय ज्यावाणेय त्रिगर्त भरत उशीनर ॥ इति यौधेयादिः ॥ १९४ ॥

४ । ३ स्थूलादिभ्यः प्रकारवचने कन् २०७५ ॥ स्थूल अण्ड माषेषु (माष इषु) । कृष्ण तिलेषु । यव व्रीहिषु । इक्षु तिल । पाद्यकालावदातसुरायाम् । गोमूत्र आच्छादने । सुरा अहौ । जीर्ण शालिषु । पत्रमूल समस्तो व्यस्तश्च ॥ कुमारीपुत्र कुमारीश्वशुर मणि ॥ इति स्थूलादिः ॥ १९५ ॥

४ । २९ यावादिभ्यः कन् २०९७ ॥ याव मणि अस्थि [तालु] जानु सान्द्र पीत स्तम्ब । ऋतावुष्णशीते । पशौ लूनविपाते । अण्ड निपुणे । पुत्र कृत्रिमे । स्नात वेदसमाप्तौ । शून्य रिक्ते । दान कुत्सिते । तनु सूत्रे । ईयसश्च । ज्ञात अज्ञात । कुमारीक्रीडनकानि च (कुमारक्रीडनकानि च) ॥ इति यावादिः ॥ १९६ ॥

४ । ३४ विनयादिभ्यष्ठक् २१०२ ॥ विनय समय । उपायो ह्रस्वत्वं च । संप्रति संगति कथंचित् अकस्मात् समाचार उपचार समाय (समयाचार) व्यवहार संप्रदान समुत्कर्ष समूह विशेष अत्यय ॥ इति विनयादिः ॥ १९७ ॥

४ । ३८ प्रज्ञादिभ्यश्च २१०६ ॥ प्रज्ञ वणिज् उशिज् उष्णिज् प्रत्यक्ष [विद्वस्] विदन् षोडन् विद्या मनस् । श्रोत्र शरीरे । जुह्वत् । कृष्ण मृगे । चिकीर्षत् चोर शत्रु योध चक्षुस् वसु [एनस्] मरुत् क्रुञ्च सत्वन्तु दशार्ह वयस् [व्याकृत] असुर रक्षस् पिशाच अशनि कार्षापण देवता बन्धु ॥ इति प्रज्ञादिः ॥ १९८ ॥

४ । ४४ आद्यादिभ्य उपसंख्यानम् (वा ३३४१) ॥ आदि मध्य अन्त पृष्ठ पार्श्व ॥ इत्याद्यादिः ॥ आकृतिगणः ॥ १९९ ॥

४ । १०७ अव्ययीभावे शरत्प्रभृतिभ्यः ६७७ ॥ शरद् विपाश् अनस् मनस् उपानह् अनडुह् दिव् हिमवत् हिरुक् विद् सद् दिश् दृश् विश् चतुर् त्यद् तद् यद् कियत् । जराया जरस् च । प्रतिपरसमनुभ्योऽक्ष्णः । पथिन् ॥ इति शरदादिः ॥ २०० ॥

४ । १२८ द्विदण्ड्यादिभ्यश्च ८६७ ॥ द्विदण्डि द्विमुसलि उभाञ्जलि उभयाञ्जलि उभादन्ति उभयादन्ति उभाहस्ति उभयाहस्ति उभाकर्णि उभयाकर्णि उभापाणि उभयापाणि उभा-

बाहु उभयाबाहु एकपदि प्रोष्ठपदि आच्यपदि (आढ्यपदि) सपदि निकुच्यकर्णि संहतपुच्छि अन्तेवासि ॥ इति द्विदण्ड्यादिः ॥ २०१ ॥

४ । १३८ पादस्य लोपोऽहस्त्यादिभ्यः ८७७ ॥ हस्तिन् [कुद्दाल अश्व कशिक कुरुत] कटोल कटोलक गण्डोल गण्डोलक कण्डोल कण्डोलक अज कपोत जाल गण्ड महेल दासी गणिका कुसूल ॥ इति हस्त्यादिः ॥ २०२ ॥

४ । १३९ कुम्भपदीषु च ८७८ ॥ कुम्भपदी एकपदी जालपदी [शूलपदी] मुनिपदी गुणपदी शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी [तृणपदी] द्विपदी त्रिपदी षट्पदी दासीपदी शितिपदी विष्णुपदी सुपदी निष्पदी आर्द्रपदी कुणिपदी कृष्णपदी शुचिपदी द्रोणीपदी (द्रोणपदी) द्रुपदी सूकरपदी शकृत्पदी अष्टापदी स्थूणापदी अपदी सूचीपदी ॥ इति कुम्भपद्यादिः ॥ २०३ ॥

४ । १५१ उरःप्रभृतिभ्यः कप् ८८९ ॥ उरस् सर्पिस् उपानह् पुमान् अनड्वान् पयः नौः लक्ष्मीः दधि मधु शाली (शालिः) । अर्थान्नञः ॥ इत्युरःप्रभृतयः ॥ २०४ ॥

इति पञ्चमोऽध्यायः ।

षष्ठोऽध्यायः ।

१ । ९४ शकन्ध्वादिषु पररूपं वाच्यम् (वा३६३०) ॥ शकन्धुः कर्कन्धुः कुलटा ॥ सीमन्तः केशवेशेषु । हलीषा मनीषा लाङ्गलीषा पतञ्जलिः । सारङ्गः पशुपक्षिणोः ॥ इति शकन्ध्वादिः ॥ २०५ ॥

१ । १५७ पारस्करप्रभृतीनि च संज्ञायाम् १०७१ ॥ पारस्करो देशः । कारस्करो वृक्षः । रथस्या नदी । किष्कुः प्रमाणम् । किष्किन्धा गुहा । तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च । प्रातुम्पतौ गवि कर्तरि ॥ इति पारस्करादिः ॥ २०६ ॥

१ । १६० उञ्छादीनां च ३६८१ ॥ उञ्छ म्लेच्छ जञ्ज नल्प (जल्प) जप वध । युग कालविशेषे रथाद्युपकरणे च । गरो दूष्ये (गरो दूष्ये) । वेदवेगवेष्टबन्धाः करणे । स्तुयुद्रुवश्छन्दसि । वर्तनि स्तोत्रे । श्वभ्रे दरः । साम्वतापौ भावगर्हायाम् । उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थभोगमन्थाः । इत्युञ्छादिः ॥ २०७ ॥

१ । २०३ वृषादीनां च ३६९१ ॥ वृषः जनः ज्वरः ग्रहः हयः गयः नयः तायः तयः चयः अमः वेदः सूदः अंशः गुहा । शमरणौ संज्ञायां संमतौ भावकर्मणोः । मन्त्रः शान्तिः कामः यामः आरा धारा कारा वहः कल्पः पादः ॥ इति वृषादिः ॥ आकृतिगणः ॥ अविहितलक्षणमाद्युदात्तत्वं वृषादिषु ज्ञेयम् ॥ २०८ ॥

२ । २४ विस्पष्टादीनि गुणवचनेषु ३७५८ ॥ विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण ॥ इति विस्पष्टादिः ॥ २०९ ॥

२ । ३७ कार्तकौजपादयश्च ३७७१ ॥ कार्तकौजपौ सावर्णिमाण्डूकेयौ (सावर्णिमाण्डूकेयौ) अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शैतिकाक्षपाञ्चालेयाः कटुकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः आर्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदानच्युताः कटकालापाः कठ-

कौथुमाः कौथुमलौकाक्षाः स्त्रीकुमारम् मौदपैप्पलादाः वत्सजरन्तः सौश्रुतपार्थवाः जरामृत्यू याज्यानुवाक्ये ॥ इति कार्तकौजपादिः ॥ २१० ॥

२ । ४२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ३७७६ ॥ दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः (वसूनितिः) औषधिः चन्द्रमाः ॥ इति दासीभारादिः ॥ आकृतिगणः ॥ २११ ॥

२ । ८१ युक्तारोह्यादयश्च ३८१५ ॥ युक्तारोही आगतरोही आगतयोधी आगतवञ्ची आगतनन्दी आगतप्रहारी आगतमत्स्यः क्षीरहोता भागिनीभर्ता ग्रामगोधुक् अश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकशितिपाद् । पात्रेसमितादयश्च ॥ इति युक्तारोह्यादिः ॥ २१२ ॥

२ । ८५ घोषादिषु च ३८१९ ॥ घोष घट (कट) वल्लभ ह्रद बदरी पिङ्गल (पिंगली) पिशङ्ग माला रक्षा शाला (वृट्) कूट (कट्) शाल्मली अश्वत्थ तृण [शिल्पी] मुनि प्रेक्षाकू (प्रेक्षा) ॥ इति घोषादिः ॥ २१३ ॥

२ । ८६ छात्र्यादयः शालायाम् ३८२० ॥ छात्रि पेलि भाण्डि व्याडि आखण्डि आटि गोमि ॥ इति छात्र्यादिः ॥ २१४ ॥

२ । ८७ प्रस्थेऽवृद्धमकर्क्यादीनाम् ३८२१ ॥ कर्कि (कर्की) मघी मकरी कर्कन्धु शमी करीरि (करीर) कन्दुक कुबल (कवल) बदरी ॥ इति कर्क्यादिः ॥ २१५ ॥

२ । ८८ मालादीनां च ३८२२ ॥ माला शाला शोणा (शोण) द्राक्षा क्षाक्षा क्षामा काञ्ची एक काम ॥ इति मालादिः ॥ २१६ ॥

२ । ११८ क्रत्वादयश्च ३८५२ ॥ क्रतु दृशीक प्रतीक प्रतूर्ति हव्य भग ॥ इति क्रत्वादिः ॥ २१७ ॥

२ । १२५ आदिश्चिहणादीनाम् ३८५९ ॥ चिहण मदुर मद्रुमर वैतुल पटत्क वैडालिकर्णक वैडालिकर्णि कुक्कुट चिक्कण चित्कण ॥ इति चिहणादिः ॥ २१८ ॥

२ । १३१ वर्ग्यादयश्च ३८६५ ॥ दिगादिषु वर्गादयस्त एव दन्ता वर्ग्यादयः ॥ २१९ ॥

२ । १३४ चूर्णादीन्यप्राणिषष्ठ्याः ३८६८ ॥ चूर्ण करिव करिप शाकिन शाकट द्राक्षा तूस्त कुन्दुम दलप चमसी चक्कन चौल ॥ इति चूर्णादिः ॥ २२० ॥

२ । १४० उभे वनस्पत्यादिषु युगपत् ३८७४ ॥ वनस्पतिः बृहस्पतिः शचीपतिः तनूनपात् नराशंसः शुनःशेपः शण्डामर्कौ तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्युः ॥ इति वनस्पत्यादिः ॥ २२१ ॥

२ । १४६ संज्ञायामनाचितादीनाम् ३८८० ॥ आचित पर्याचित आस्थापित परिगृहीत निरुक्त प्रतिपन्न अपश्लिष्ट प्रश्लिष्ट उपहित उपस्थित संहितागवि ॥ इत्याचितादिः ॥ २२२ ॥

२ । १४७ प्रवृद्धादीनां च ३८८१ ॥ प्रवृद्धं यानम् । प्रवृद्धो वृषलः । प्रयुता सूष्णवः । आकर्षेऽवहितः । अवहितो भोगेषु । खट्वारूढः । कविशस्तः ॥ इति प्रवृद्धादिः ॥ २२३ । आकृतिगणोऽयम् ॥ तेन । प्रवृद्धं यानम् । अप्रवृद्धो वृषकृतो रथ इत्यादि ॥

२ । १६० कृत्योकेष्णुच्चार्वादयश्च ३८९४ ॥ चारु साधु यौधिक (यौधकि) अनङ्ग

भेजय वदान्य अकस्मात् । वर्तमानवर्धमानत्वरमाणध्रियमाणक्रीयमाणरोचमानशोभमानाः संज्ञायाम् । विकारसदृशे व्यस्तसमस्ते । गृहपति गृहपतिक । राजाह्नोश्छन्दसि ॥ इति चार्वादिः ॥ २२४ ॥

२ । १७६ न गुणादयोऽवयवाः ३९१० ॥ गुण अक्षर अध्याय सूक्त छन्दोमान ॥ इति गुणादिः ॥ आकृतिगणः ॥ २२५ ॥

२ । १८४ निरुदकादीनि च ३९१८ ॥ निरुदक निरुपल निर्मक्षिक निर्मशक निष्कालक निष्कालिक निष्पेष दुस्तरीप निस्तरीप निस्तरीक निराजिन [उदजिन] उपाजिन । परेर्हस्तपादकेशकर्षाः ॥ इति निरुदकादिः ॥ आकृतिगणः ॥ २२६ ॥

२ । १९३ प्रतेरंश्वादयस्तत्पुरुषे ३९२७ ॥ अंशु जन [राजन्] उष्ट्र खेटक अजिर आर्द्रा श्रवण कृत्तिका आर्धपुर ॥ इत्यंश्वादिः ॥ २२७ ॥

२ । १९४ उपाद्द्व्यजजिनमगौरादयः ३९२८ ॥ गौर तैष तैल लेट लोट जिह्वा कृष्ण कन्या गुध कल्प पाद ॥ इति गौरादिः ॥ २२८ ॥

२ । १९९ त्रिचक्रादीनां छन्दस्युपसंख्यानम् (वा ३८६८) ॥ त्रिचक्र त्रिवृत् त्रिवन्धुर ॥ इति त्रिचक्रादिः ॥ आकृतिगणः ॥ २२९ ॥

३ । ३४ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ८३१ ॥ प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा स्वसा (स्वा) कान्ता [क्षान्ता] समा चपला दुहिता वामना [तनया] ॥ इति प्रियादिः ॥ २३० ॥

३ । ३५ तसिलादिष्वा कृत्वसुचः ८३६ ॥ तसिल् त्रत् तरप् तमप् चरट् जातीयर् कल्पप् देशीयर् रूपप् पाशप् थल् थाल् दार्हिल् तिल् थ्यन् ॥ इति तसिलादयः ॥ २३१ ॥

३ । ४२ कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः (वा ३९३५) ॥ कुक्कुटी मृगी काकी अण्ड पद शाव भुकुंस भृकुटी ॥ इति कुक्कुट्याद्यण्डादी ॥ २३२ ॥ २३३ ॥

३ । १०९ पृषोदरादीनि यथोपदिष्टम् १०३४ ॥ पृषोदर पृषोत्थान बलाहक जीमूत श्मशान उलूखल पिशाच वृसी मयूर ॥ इति पृषोदरादिः ॥ आकृतिगणः ॥ २३४ ॥

३ । ११७ वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् १०३८ ॥ कोटर मिश्रक सिध्रक पुरग सारिक (शारिक) ॥ इति कोटरादिः ॥ २३५ ॥ किंशुलुक शाल्व नध्र (नड) अञ्जन भञ्जन लोहित कुक्कुट ॥ इति किंशुलुकादिः ॥ २३६ ॥

३ । ११९ मतौ बह्वचोऽनजिरादीनाम् १०४१ ॥ अजिर खदिर पुलिन हंसक (हंस) कारण्ड (कारण्डव) चक्रवाक ॥ इत्यजिरादिः ॥ २३७ ॥

३ । १२० शरादीनां च १०४२ ॥ शर वंश धूम अहि कपि मणि मुनि शुचि हनु ॥ इति शरादिः ॥ २३८ ॥

३ । १२१ अपील्वादीनामिति वक्तव्यम् (वा ४००४) ॥ पीलु दारु रुचि चारु गम् कम् ॥ इति पील्वादिः ॥ २३९ ॥

४ । १९३ बिल्वकादिभ्यश्छस्य लुक् १३११ ॥ छविधानार्थं ये नडादयस्ते यदा छसंनियोगे कृतकुगागमास्ते बिल्वकादयः ॥ २४० ॥

इति षष्ठोऽध्यायः ।

सप्तमोऽध्यायः ।

१ । ४९ स्नात्व्यादयश्च ३५७१ ॥ स्नात्वी पीत्वी ॥ इति स्नात्व्यादिः ॥ आकृतिगणः ॥ २४१ ॥

३ । ४ द्वारादीनां च १३८६ ॥ द्वार स्वर [स्वाध्याय] व्यल्कश स्वस्ति स्वर् स्फ्यकृत् (सम्यकृत्) स्वादुमृदु[1] श्वस् श्वन् स्व ॥ इति द्वारादिः ॥ २४२ ॥

३ । ७ स्वागतादीनां च १५४९ ॥ स्वागत स्वध्वर स्वङ्ग व्यङ्ग व्यड व्यवहार स्वपिति (स्वपति) ॥ इति स्वागतादिः ॥ २४३ ॥

३ । २० अनुशतिकादीनां च १४३८ ॥ अनुशतिक अनुहोड अनुसंवरण (अनुसंचरण) अनुसंवत्सर अङ्गारवेणु असिहत्य [अस्यहत्य] अस्यहेति वध्योग पुष्करसद् अनुहरत् कुरुकत कुरुपञ्चाल उदकशुद्ध इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि प्रयोग परस्त्री । राजपुरुषात्ष्यञि । सूत्रनड ॥ इत्यनुशतिकादिः ॥ आकृतिगणोऽयम् ॥ २४४ ॥ तेन । अभिगम आधिभूत अधिदेव चतुर्विद्या इत्यादि ॥

३ । ४५ क्षिपकादीनां चोपसंख्यानम् (वा ४५२४) ॥ क्षिपका ध्रुवका चरका सेवका करका चटका अवका लहका अलका कन्यका ध्रुवका एडका ॥ इति क्षिपकादिः ॥ आकृतिगणः ॥ २४५ ॥

३ । ५३ न्यङ्क्वादीनां च २८६४ ॥ न्यङ्कु मद्गु भृगु दूरेपाक फलेपाक क्षणेपाक दूरेपाका फलेपाका दूरेपाकु फलेपाकु तक्र (तत्र) वक्र (चक्र) व्यतिषङ्ग [अनुषङ्ग] अवसर्ग [उपसर्ग] श्वपाक मांसपाक (मासपाक) मूलपाक कपोतपाक उलूकपाक । संज्ञायां मेघनिदाघावदाघार्घाः । न्यग्रोध वीरुत् ॥ इति न्यङ्क्वादिः ॥ २४६ ॥

४ । ३ कणादीनां चेति वक्तव्यम् (वा ४६०७) ॥ कण रण भण श्रण लुप हेठ हायि वाणि (चाणि) लोटि (लोठि) लोपि ॥ इति कणादिः ॥ २४७ ॥

इति सप्तमोऽध्यायः ।

अष्टमोऽध्यायः ।

१ । २७ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ३९३४ ॥ गोत्र ब्रुव प्रवचन प्रहसन प्रकथन प्रत्ययन प्रपञ्च प्राय न्याय प्रचक्षण विचक्षण अवचक्षण स्वाध्याय भूयिष्ठ (भूयिष्ट) वानाम ॥ इति गोत्रादिः ॥ २४८ ॥

---

१ भिन्नपदत्वे मृदुग्रहणवैयर्थ्यम् । तत्र यकारवकाराभावात् ।

१ । ६७ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ३९७४ ॥ काष्ठ दारुण अमातापुत्र वेश अनाज्ञात अनुज्ञात अपुत्र अयुत अद्भुत [अनुक्त] भृश घोर सुख परम सु अति ॥ इति काष्ठादिः ॥ २४९ ॥

२ । ९ मातुपधायाश्च मतोर्वोऽयवादिभ्यः १८९७ ॥ यव दल्मि ऊर्मि (उर्मि) भूमि कृमि कुञ्चा वशा द्राक्षा ध्राक्षा ध्रजि (ध्रजि) ध्वजि निजि सिजि सञ्जि हरित् ककुत् मरुत् गरुत् इक्षु द्रु मधु ॥ इति यवादिः ॥ आकृतिगणः ॥ २५० ॥

२ । ७० अहरादीनां पत्यादिषूपसंख्यानम् (वा ३६०४) ॥ अहर् गीर् धूर् ॥ इत्यहरादिः ॥ २५१ ॥ पति गण पुत्र ॥ इति पत्यादिः ॥ २५२ ॥

३ । ४८ कस्कादिषु च १४४ ॥ कस्कः कौतस्कुतः भ्रातुष्पुत्रः शुनस्कर्णः सद्यस्कालः सद्यस्क्रीः साद्यस्क्रः कांस्कान् सर्पिष्कुण्डिका धनुष्कपालम् बर्हिष्पलम् (बर्हिष्पलम्) यजुष्पात्रम् अयस्कान्तः तमस्काण्डः अयस्काण्डः मेदस्पिण्डः [भास्करः अहस्करः] ॥ इति कस्कादिः ॥ आकृतिगणः ॥ २५३ ॥

३ । ९८ सुषामादिषु च १०२२ ॥ सुषामा निःषामा दुःषामा सुषेधः निषेधः (निःषेधः) दुःषेधः सुषंधिः निःषंधिः दुःषंधिः सुष्ठु दुष्ठु । गौरिषक्थः संज्ञायाम् । प्रतिष्णिका जलाषाहम् (जलाषाडम्) नौषेचनम् दुन्दुभिषेवणम् (दुन्दुभिषेचनम्) एति संज्ञायामगात् । नक्षत्राद्वा । हरिषेणः रोहिणीषेणः ॥ इति सुषामादिः ॥ आकृतिगणः ॥ २५४ ॥

३ । ११० न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ३१६८ ॥ सवने सवने । सूते सूते । सोमे सोमे । सवनमुखे सवनमुखे । किंसं किंसम् (किंसः किंसः) । अनुसवनमनुसवनम् । गोसनिं गोसनिम् । अश्वसनिमश्वसनिम् ॥ पाठान्तरम् ॥ सवने सवने सवनमुखे सवनमुखे । अनुसवनमनुसवनम् । संज्ञायां बृहस्पतिसवः ॥ शकुनिसवनम् । सोमे सोमे । सुते सुते । संवत्सरे संवत्सरे । बिसं बिसम् । किसं किसम् । मुसलं मुसलम् । गोसनिम् अश्वसनिम् ॥ इति सवनादिः ॥ २५५ ॥

४ । ६ इरिकादिभ्यः प्रतिषेधो वक्तव्यः (वा ४९७६) ॥ इरिका मिरिका तिमिरा ॥ इतीरिकादिः ॥ आकृतिगणः ॥ २५६ ॥

४ । १० वाप्रकरणे गिरिनद्यादीनामुपसंख्यानम् (वा ४९८०) ॥ गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान माषोन आर्गयन ॥ इति गिरिनद्यादिः ॥ आकृतिगणः ॥ २५७ ॥

४ । ३९ क्षुभ्नादिषु च ७९२ ॥ क्षुभ्ना नृनमन नन्दिन् नन्दन नगर । एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति । हरिनन्दी हरिनन्दनः गिरिनगरम् । नृतिर्यङि प्रयोजयन्ति । नरीनृत्यते । नर्तन गहन नन्दन निवेश निवास अग्नि अनूप । एतान्युत्तरपदानि प्रयोजयन्ति । परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्भानूपः । आचार्यादणत्वं च । आचार्यभोगीनः ॥ आकृतिगणोऽयम् ॥ पाठान्तरम् ॥ क्षुभ्ना तृप्नु नृनमन नरनगर नन्दन । यङ्नृती । गिरिनदी गृहगमन निवेश निवास अग्नि अनूप आचार्यभोगीन

चतुर्हायन । इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका तिमिर समीर कुबेर हरि कर्मार ॥ इति क्षुभ्नादिः ॥ २९८ ॥

इत्यष्टमोऽध्यायः ।

इति श्रीपाणिनिमुनिप्रणीतो गणपाठः समाप्तः ।

---

(३) पाणिनीयो धातुपाठः ।

१ भू सत्तायाम् ॥ उदात्तः परस्मैभाषः ॥ २ एध वृद्धौ । ३ स्पर्ध संघर्षे । ४ गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । ५ बाधृ लोडने । ६ नाथृ ७ नाधृ याच्ञोपतापैश्वर्याशीःषु । ८ दध धारणे । ९ स्कुदि आप्रवणे । १० श्विदि श्वैत्ये । ११ वदि अभिवादनस्तुत्योः । १२ भदि कल्याणे सुखे च । १३ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । १४ स्पदि किंचिच्चलने । १५ क्लिदि परिदेवने । १६ मुद हर्षे । १७ दद दाने । १८ ष्वद १९ स्वर्द आस्वादने । २० उर्द माने क्रीडायां च । २१ कुर्द २२ खुर्द २३ गुर्द २४ गुद क्रीडायामेव । २५ षूद क्षरणे । २६ ह्राद अव्यक्ते शब्दे । २७ ह्लादी सुखे च । २८ स्वाद आस्वादने । २९ पर्द कुत्सिते शब्दे । ३० यती प्रयत्ने । ३१ युतृ ३२ जुतृ भासने । ३३ विथृ ३४ वेथृ याचने । ३५ श्रथि शैथिल्ये । ३६ ग्रथि कौटिल्ये । ३७ कत्थ श्लाघायाम् ॥ एधादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ३८ अत सातत्यगमने । ३९ चिती संज्ञाने । ४० च्युतिर् आसेचने । ४१ श्चुतिर् क्षरणे । ४२ मन्थ विलोडने । ४३ कुथि ४४ पुथि ४५ लुथि ४६ मथि हिंसासंक्लेशनयोः । ४७ षिध गत्याम् । ४८ षिधू शास्त्रे माङ्गल्ये च । ४९ खादृ भक्षणे । ५० खद स्थैर्ये हिंसायां च । ५१ बद स्थैर्ये । ५२ गद व्यक्तायां वाचि । ५३ रद विलेखने । ५४ णद अव्यक्ते शब्दे । ५५ अर्द गतौ याचने च । ५६ नर्द ५७ गर्द शब्दे । ५८ तर्द हिंसायाम् । ५९ कर्द कुत्सिते शब्दे । ६० खर्द दन्दशूके । ६१ अति ६२ अदि बन्धने । ६३ इदि परमैश्वर्ये । ६४ बिदि अवयवे ॥ भिदि इत्येके ॥ ६५ गडि वदनैकदेशे । ६६ णिदि कुत्सायाम् । ६७ टुनदि समृद्धौ । ६८ चदि आह्लादे । ६९ त्रदि चेष्टायाम् । ७० कदि ७१ क्रदि ७२ क्लदि आह्वाने रोदने च । ७३ क्लिदि परिदेवने । ७४ शुन्ध शुद्धौ ॥ अतादय उदात्ता उदात्तेतः परस्मैभाषः ॥ ७५ शीकृ सेचने । ७६ लोकृ दर्शने । ७७ श्लोकृ संघाते । ७८ द्रेकृ ७९ ध्रेकृ शब्दोत्साहयोः । ८० रेकृ शङ्कायाम् । ८१ सेकृ ८२ स्रेकृ ८३ स्रकि ८४ श्रकि ८५ श्लकि गतौ । ८६ शकि शङ्कायाम् । ८७ अकि लक्षणे । ८८ वकि कौटिल्ये । ८९ मकि मण्डने । ९० कक लौल्ये । ९१ कुक ९२ वृक आदाने । ९३ चक तृप्तौ प्रतिघाते च । ९४ ककि ९५ वकि ९६ श्वकि ९७ त्रकि ९८ ढौकृ ९९ त्रौकृ १०० ष्वष्क १०१ वस्क १०२ मस्क १०३ टिकृ १०४ टीकृ १०५ तिकृ १०६ तीकृ १०७ रघि १०८ लघि गत्यर्थाः ॥ तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि ॥ १०९ अघि ११० वघि १११ मघि गत्याक्षेपे । मघि कैतवे च ॥ ११२ राघृ ११३ लाघृ ११४ द्राघृ सामर्थ्ये ॥ ध्राघृ इत्यपि केचित् । द्राघृ आयामे च ॥ ११५ श्लाघृ कत्थने ॥ शीकादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ११६ फक्क नीचै-

गतौ । ११७ तक हसने । ११८ तकि कृच्छ्रजीवने । ११९ बुक्क भषणे । १२० कख हसने ।
१२१ ओखृ १२२ राखृ १२३ लाखृ १२४ द्राखृ १२५ ध्राखृ शोषणालमर्थयोः । १२६ शाखृ
१२७ श्लाखृ व्याप्तौ । १२८ उख १२९ उखि १३० वख १३१ वखि १३२ मख १३३ मखि
१३४ णख १३५ णखि १३६ रख १३७ रखि १३८ लख १३९ लखि १४० इख
१४१ इखि १४२ ईखि १४३ वल्ग १४४ रगि १४५ लगि १४६ अगि १४७
वगि १४८ मगि १४९ तगि १५० त्वगि १५१ श्रगि १५२ श्लगि १५३ इगि १५४ रिगि
१५५ लिगि गत्यर्थाः ॥ रिख त्रख त्रिखि शिखि इत्यपि केचित् । त्वगि कम्पने च ॥ १५६
युगि १५७ जुगि १५८ बुगि वर्जने । १५९ घघ हसने । १६० मघि मण्डने । १६१ शिघि
आघ्राणे ॥ फक्कादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १६२ वर्च दीप्तौ । १६३ षच
सेचने सेवने च । १६४ लोचृ दर्शने । १६५ शच व्यक्तायां वाचि । १६६ श्वच १६७ श्वचि
गतौ । १६८ कच बन्धने । १६९ कचि १७० काचि दीप्तिबन्धनयोः । १७१ मच १७२ मुचि
कल्कने ॥ कथन इत्यन्ये ॥ १७३ मचि धारणोच्छ्रायपूजनेषु । १७४ पचि व्यक्तीकरणे ।
१७५ ष्टुच प्रसादे । १७६ ऋज गतिस्थानार्जनोपार्जनेषु । १७७ ऋजि १७८ भृजी भर्जने ।
१७९ एजृ १८० भ्रेजृ १८१ भ्राजृ दीप्तौ । १८२ ईज गतिकुत्सनयोः ॥ वर्चादय उदात्ता
अनुदात्तेत आत्मनेभाषाः ॥ १८३ शुच शोके । १८४ कुच शब्दे तारे । १८५ कुन्च
१८६ क्रुन्च कौटिल्याल्पीभावयोः । १८७ लुन्च अपनयने । १८८ अन्चु गतिपूजनयोः । १८९
वन्चु १९० चन्चु १९१ तन्चु १९२ त्वन्चु १९३ म्रुन्चु १९४ म्लुन्चु १९५ म्रुचु १९६ म्लुचु
गत्यर्थाः । १९७ ग्रुचु १९८ ग्लुचु १९९ कुजु २०० खुजु स्तेयकरणे । २०१ ग्लुन्चु २०२
षस्ज गतौ । २०३ गुजि अव्यक्ते शब्दे । २०४ अर्च पूजायाम् । २०५ म्लेछ अव्यक्ते शब्दे ।
२०६ लछ २०७ लाछि लक्षणे । २०८ वाछि इच्छायाम् । २०९ आछि आयामे । २१०
ह्रीछ लज्जायाम् । २११ हुर्छा कौटिल्ये । २१२ मुर्छा मोहसमुच्छ्राययोः । २१३ स्फुर्छा
विस्तृतौ । २१४ युछ प्रमादे । २१५ उछि उञ्छे । २१६ उछी विवासे । २१७ ध्रज २१८
ध्रजि २१९ धृज २२० धृजि २२१ ध्वज २२२ ध्वजि गतौ । २२३ कूज अव्यक्ते शब्दे ।
२२४ अर्ज २२५ षर्ज अर्जने । २२६ गर्ज शब्दे । २२७ तर्ज भर्त्सने । २२८ कर्ज व्यथने ।
२२९ खर्ज पूजने च । २३० अज गतिक्षेपणयोः । २३१ तेज पालने । २३२ खज मन्थे ।
२३३ खजि गतिवैकल्ये । २३४ एजृ कम्पने । २३५ टुओस्फूर्जा वज्रनिर्घोषे । २३६ क्षि
क्षये । २३७ क्षीज अव्यक्ते शब्दे । २३८ लज २३९ लजि भर्जने । २४० लाज २४१ लाजि
भर्त्सने च । २४२ जज २४३ जजि युद्धे । २४४ तुज हिंसायाम् । २४५ तुजि पालने । २४६
गज २४७ गजि २४८ गृज २४९ गृजि २५० मुज २५१ मुजि शब्दार्थाः । गज मदने च ।
२५२ वज २५३ व्रज गतौ ॥ शुचादय उदात्ता उदात्तेतः (क्षिवर्जं) परस्मैभाषाः ॥
२५४ अट्ट अतिक्रमहिंसयोः । २५५ वेष्ट वेष्टने । २५६ चेष्ट चेष्टायाम् । २५७ गोष्ट २५८
लोष्ट संघाते । २५९ घट्ट चलने । २६० स्फुट विकसने । २६१ अठि गतौ । २६२ वठि
एकचर्यायाम् । २६३ मठि २६४ कठि शोके । २६५ मुठि पालने । २६६ हेठ विबाधायाम् ।
२६७ एठ च । २६८ हिडि गत्यनादरयोः । २६९ हडि संघाते । २७० कुडि दाहे । २७१
वुडि विभाजने । २७२ मडि च । २७३ भडि परिभाषणे । २७४ पिडि संघाते । २७५

मुडि मार्जने । २७६ तुडि तोडने । २७७ हुडि वरणे ॥ हरण इत्येके ॥ २७८ चडि कोपे । २७९ शडि रुजायां संघाते च । २८० तडि ताडने । २८१ पडि गतौ । २८२ कडि मदे । २८३ खडि मन्थे । २८४ हेडृ २८५ होडृ अनादरे । २८६ बाडृ आप्लाव्ये । २८७ द्राडृ २८८ ध्राडृ विशरणे । २८९ शाडृ श्लाघायाम् ॥ अहादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ २९० शौटृ गर्वे । २९१ यौटृ बन्धे । २९२ म्लेटृ २९३ म्रेडृ उन्मादे । २९४ कटे वर्षावरणयोः ॥ चटे इत्येके ॥ २९५ अट २९६ पट गतौ । २९७ रट परिभाषणे । २९८ लट बाल्ये । २९९ शट रुजाविशरणगत्यवसादनेषु । ३०० वट वेष्टने । ३०१ किट ३०२ खिट त्रासे । ३०३ शिट ३०४ षिट अनादरे । ३०५ जट ३०६ झट संघाते । ३०७ भट भृतौ । ३०८ तट उच्छ्राये । ३०९ खट काङ्क्षायाम् । ३१० णट नृतौ । ३११ पिट शब्दसंघातयोः । ३१२ हट दीप्तौ ३१३ षट अवयवे । ३१४ लुट विलोडने ॥ डान्तोऽयमित्येके ॥ ३१५ चिट परप्रेष्ये । ३१६ विट शब्दे । ३१७ बिट आक्रोशे ॥ हिट इत्येके ॥ ३१८ इट ३१९ किट ३२० कटी गतौ । ३२१ मडि भूषायाम् । ३२२ कुडि वैकल्ये । ३२३ मुड ३२४ प्रुड मर्दने । ३२५ चुडि अल्पीभावे । ३२६ मुडि खण्डने ॥ पुडि चेत्येके ॥ ३२७ रुटि ३२८ लुटि स्तेये ॥ रुठि लुठि इत्येके । रुडि लुडि इत्यपरे ॥ ३२९ स्फुटिर विशरणे ॥ स्फुटि इत्यपि केचित् ॥ ३३० पठ व्यक्तायां वाचि । ३३१ वठ स्थौल्ये । ३३२ मठ मदनिवासयोः । ३३३ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे ॥ रठ इत्येके ॥ ३३५ हठ प्लुतिशठत्वयोः ॥ बलात्कार इत्यन्ये ॥ ३३६ रुठ ३३७ लुठ ३३८ उठ उपघाते ॥ ऊठ इत्येके ॥ ३३९ पिठ हिंसासंक्लेशनयोः । ३४० शठ कैतवे च । ३४१ शुठ प्रतिघाते ॥ शुठि इति स्वामी । ३४२ कुठि च । ३४३ लुठि आलस्ये प्रतिघाते च । ३४४ शुठि शोषणे । ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुड्ड भावकरणे । ३४८ अड्ड अभियोगे । ३४९ कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दोपधाः ॥ ३५० क्रीडृ विहारे । ३५१ तुडृ तोडने ॥ तूडृ इत्येके ॥ ३५२ हुडृ ३५३ हूडृ ३५४ होडृ गतौ । ३५५ रौडृ अनादरे । ३५६ रोडृ ३५७ लोडृ उन्मादे । ३५८ अड उद्यमे । ३५९ लड विलासे ॥ लल इत्येके ॥ ३६० कड मदे ॥ कडि इत्येके ॥ ३६१ गडि वदनैकदेशे ॥ शौटादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ३६२ तिपृ ३६३ तेपृ ३६४ ष्टिपृ ३६५ ष्टेपृ क्षरणार्थाः ॥ तेपृ कम्पने च ॥ ३६६ ग्लेपृ दैन्ये । ३६७ टुवेपृ कम्पने । ३६८ केपृ ३६९ गेपृ ३७० ग्लेपृ च । ३७१ मेपृ ३७२ रेपृ ३७३ लेपृ गतौ ॥ ३७४ त्रपूष् लज्जायाम् । ३७५ कपि चलने । ३७६ रबि ३७७ लबि ३७८ अबि शब्दे । ३७९ लबि अवस्रंसने च । ३८० कबृ वर्णे । ३८१ क्लीबृ अधाष्टर्ये । ३८२ क्षीबृ मदे । ३८३ शीभृ कत्थने । ३८४ चीभृ च । ३८५ रेभृ शब्दे ॥ अभिरभी क्वचित्पठ्येते ॥ ३८६ ष्टभि ३८७ स्कभि प्रतिबन्धे । ३८८ जभि ३८९ जृभि गात्रविनामे । ३९० शल्भ कत्थने । ३९१ वल्भ भोजने । ३९२ गल्भ धाष्टर्ये । ३९३ श्रम्भु प्रमादे ॥ दन्त्यादिश्च ॥ ३९४ ष्टुभु स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः । तिपिस्त्वनुदात्तः ॥ ३९५ गुपू रक्षणे । ३९६ धूप संतापे । ३९७ जप ३९८ जल्प व्यक्तायां वाचि । जप मानसे च । ३९९ चप सान्त्वने । ४०० षप समवाये । ४०१ रप ४०२ लप व्यक्तायां वाचि । ४०३ चुप मन्दायां गतौ । ४०४ तुप ४०५ तुम्प ४०६ त्रुप

४०७ त्रुम्प ४०८ तुफ ४०९ तुम्फ ४१० त्रुफ ४११ त्रुम्फ हिंसार्थाः । ४१२ पर्प ४१३ रफ ४१४ रफि ४१५ अर्ब ४१६ पर्ब ४१७ लर्ब ४१८ बर्ब ४१९ मर्ब ४२० कर्ब ४२१ खर्ब ४२२ गर्ब ४२३ शर्ब ४२४ षर्ब ४२५ चर्ब गतौ । ४२६ कुबि आच्छादने । ४२७ लुबि ४२८ तुबि अर्दने । ४२९ चुबि वक्त्रसंयोगे । ४३० षृभु ४३१ षृम्भु हिंसार्थौ । षिभु षिम्भु इत्येके ॥ ४३२ शुभ ४३३ शुम्भ भाषणे ॥ भासन इत्येके । हिंसायामित्यन्ये ॥ गुपादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ४३४ घिणि ४३५ घुणि ४३६ घृणि ग्रहणे । ४३७ घुण ४३८ घूर्ण भ्रमणे । ४३९ पण व्यवहारे स्तुतौ च । ४४० पन च । ४४१ भाम क्रोधे । ४४२ क्षमूष् सहने । ४४३ कमु कान्तौ ॥ घिण्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ४४४ अण ४४५ रण ४४६ वण ४४७ भण ४४८ मण ४४९ कण ४५० क्वण ४५१ व्रण ४५२ भ्रण ४५३ ध्वण शब्दार्थाः ॥ धण इत्यपि केचित् ॥ ४५४ ओणृ अपनयने । ४५५ शोणृ वर्णगत्योः । ४५६ श्रोणृ संघाते । ४५७ श्लोणृ च । ४५८ पैणृ गतिप्रेरणश्लेषणेषु । ४५९ ध्रन शब्दे ॥ बण इत्यपि केचित् ॥ ४६० कनी दीप्तिकान्तिगतिषु । ४६१ ष्टन ४६२ वन शब्दे । ४६३ वन ४६४ षण संभक्तौ । ४६५ अम गत्यादिषु । ४६६ द्रम ४६७ हम्म ४६८ मीमृ गतौ । ४६९ चमु ४७० छमु ४७१ जमु ४७२ झमु अदने । ४७३ क्रमु पाद-विक्षेपे ॥ अणादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ४७४ अय ४७५ वय ४७६ पय ४७७ मय ४७८ चय ४७९ तय ४८० णय गतौ । ४८१ दय दानगतिरक्षणहिंसादानेषु । ४८२ रय गतौ । ४८३ ऊयी तन्तुसंताने । ४८४ पूयी विशरणे दुर्गन्धे च । ४८५ क्नूयी शब्दे उन्दे च । ४८६ क्ष्मायी विधूनने । ४८७ स्फायी ४८८ ओप्यायी वृद्धौ । ४८९ तायृ संतानपालनयोः । ४९० शल चलनसंवरणयोः । ४९१ वल ४९२ वल्ल संवरणे संचरणे च । ४९३ मल ४९४ मल्ल धारणे । ४९५ भल ४९६ भल्ल परिभाषणहिंसादानेषु । ४९७ कल शब्दसंख्यानयोः । ४९८ कल्ल अव्यक्ते शब्दे ॥ अशब्द इति स्वामी ॥ ४९९ तेवृ ५०० देवृ देवने । ५०१ षेवृ ५०२ गेवृ ५०३ ग्लेवृ ५०४ पेवृ ५०५ मेवृ ५०६ म्लेवृ सेवने ॥ शेवृ खेवृ क्लेवृ इत्येके ॥ ५०७ रेवृ प्लवगतौ ॥ अयादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ५०८ मव्य बन्धने । ५०९ सूर्क्ष्य ५१० ईर्क्ष्य ५११ ईर्ष्य ईर्ष्यार्थाः । ५१२ हय गतौ । ५१३ शुच्य अभिषवे ॥ चुच्य इत्येके ॥ ५१४ हर्य गतिकान्त्योः । ५१५ अल भूषणपर्याप्तिवारणेषु ॥ अयं स्वरितेदित्येके ॥ ५१६ ञिफला विशरणे । ५१७ मील ५१८ श्मील ५१९ स्मील ५२० क्ष्मील निमेषणे । ५२१ पील प्रतिष्टम्भे । ५२२ नील वर्णे । ५२३ शील समाधौ । ५२४ कील बन्धने । ५२५ कूल आवरणे । ५२६ शूल रुजायां संघोषे च । ५२७ तूल निष्कर्षे । ५२८ पूल संघाते । ५२९ मूल प्रतिष्ठायाम् । ५३० फल निष्पत्तौ ॥ ५३१ चुल्ल भावकरणे । ५३२ फुल्ल विकसने । ५३३ चिल्ल शैथिल्ये भावकरणे च । ५३४ तिल गतौ ॥ तिल्ल इत्येके ॥ ५३५ वेल्ल ५३६ चेल्ल ५३७ केल्ल ५३८ खेल्ल ५३९ क्ष्वेल्ल ५४० वेल्ल चलने । ५४१ पेल्ल ५४२ फेल्ल ५४३ शेल्ल गतौ ॥ षेल्ल इत्येके ॥ ५४४ स्खल संचलने । ५४५ खल संचये । ५४६ गल अदने । ५४७ षल गतौ । ५४८ दल विशरणे । ५४९ श्वल ५५० श्वल्ल आशुगमने । ५५१ खोल्ल ५५२ खोर्ऋ गतिप्रतिघाते । ५५३ धोर्ऋ गतिचातुर्ये । ५५४ त्सर छद्मगतौ । ५५५ क्मर हूर्च्छने । ५५६ अभ्र ५५७ वभ्र ५५८ मभ्र ५५९ चर गत्यर्थाः ॥

चरतिर्भक्षणेऽपि ॥ ५६० ष्ठिवु निरसने । ५६१ जि जये । ५६२ । जीव प्राणधारणे । ५६३ पीव ५६४ मीव ५६५ तीव ५६६ णीव स्थौल्ये । ५६७ क्षीवु ५६८ क्षेवु निरसने । ५६९ उर्वी ५७० तुर्वी ५७१ थुर्वी ५७२ दुर्वी ५७३ धुर्वी हिंसार्थाः । ५७४ गुर्वी उद्यमने । ५७५ मुर्वी बन्धने । ५७६ पुर्व ५७७ पर्व ५७८ मर्व पूरणे । ५७९ चर्व अदने । ५८० भर्व हिंसायाम् । ५८१ कर्व ५८२ खर्व ५८३ गर्व दर्पे । ५८४ अर्व ५८५ शर्व ५८६ षर्व हिंसायाम् । ५८७ इवि व्याप्तौ । ५८८ पिवि ५८९ मिवि ५९० णिवि सेचने ॥ सेवन इत्येके ॥ ५९१ हिवि ५९२ दिवि ५९३ धिवि ५९४ जिवि प्रीणनार्थाः । ५९५ रिवि ५९६ रवि ५९७ धवि गत्यर्थाः । ५९८ कृवि हिंसाकरणयोश्च । ५९९ मव बन्धने । ६०० अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु ॥ मव्याद्य उदात्ता उदात्तेतः परस्मैभाषाः । जिस्त्वनुदात्तः ॥ ६०१ धावु गतिशुद्ध्योः । उदात्तः स्वरितेदुभयतोभाषः ॥ ६०२ धुक्ष ६०३ धिक्ष संदीपनक्लेशनजीवनेषु । ६०४ वृक्ष वरणे । ६०५ शिक्ष विद्योपादाने । ६०६ भिक्ष भिक्षायामलाभे लाभे च । ६०७ क्लेश अव्यक्तायां वाचि ॥ बाधन इति दुर्गः ॥ ६०८ दक्ष वृद्धौ शीघ्रार्थे च । ६०९ दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । ६१० ईक्ष दर्शने । ६११ ईष गतिहिंसादर्शनेषु । ६१२ भाष व्यक्तायां वाचि । ६१३ वर्ष स्नेहने । ६१४ गेषृ अन्विच्छायाम् ॥ ग्लेषृ इत्येके ॥ ६१५ पेषृ प्रयत्ने । ६१६ जेषृ ६१७ णेषृ ६१८ एषृ ६१९ प्रेषृ गतौ । ६२० रेषृ ६२१ हेषृ ६२२ ह्रेषृ अव्यक्ते शब्दे । ६२३ कासृ शब्दकुत्सायाम् । ६२४ भासृ दीप्तौ । ६२५ णासृ ६२६ रासृ शब्दे । ६२७ णस कौटिल्ये । ६२८ भ्यस भये । ६२९ आङः शसि इच्छायाम् । ६३० ग्रसु ६३१ ग्लसु अदने । ६३२ ईह चेष्टायाम् । ६३३ बहि ६३४ महि वृद्धौ । ६३५ अहि गतौ । ६३६ गर्ह ६३७ गल्ह कुत्सायाम् । ६३८ बर्ह ६३९ बल्ह प्राधान्ये । ६४० वर्ह ६४१ वल्ह परिभाषणहिंसाच्छादनेषु । ६४२ प्लिह गतौ । ६४३ वेहृ ६४४ जेहृ ६४५ बाहृ प्रयत्ने ॥ जेहृ गतावपि ॥ ६४६ द्राहृ निद्राक्षये ॥ निक्षेप इत्येके ॥ ६४७ काशृ दीप्तौ । ६४८ ऊहृ वितर्के । ६४९ गाहू विलोडने । ६५० गृहू ग्रहणे । ६५१ ग्लह च । ६५२ घुषि कान्तिकरणे ॥ घष इति केचित् ॥ धुक्षादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ६५३ घुषिर् अविशब्दने । ६५४ अक्षू व्याप्तौ । ६५५ तक्षू ६५६ त्वक्षू तनूकरणे । ६५७ उक्ष सेचने । ६५८ रक्ष पालने । ६५९ णिक्ष चुम्बने । ६६० तृक्ष ६६१ स्तृक्ष ६६२ णक्ष गतौ । ६६३ वक्ष रोषे ॥ संघात इत्येके ॥ ६६४ मृक्ष संघाते ॥ म्रक्ष इत्येके ॥ ६६५ तक्ष त्वचने । ६६६ सूर्क्ष आदरे । ६६७ काक्षि ६६८ वाक्षि ६६९ माक्षि काङ्क्षायाम् । ६७० द्राक्षि ६७१ ध्राक्षि ६७२ ध्वाक्षि घोरवासिते च । ६७३ चूष पाने । ६७४ तूष तुष्टौ । ६७५ पूष वृद्धौ । ६७६ मूष स्तेये । ६७७ लूष ६७८ रूष भूषायाम् । ६७९ शूष प्रसवे । ६८० यूष हिंसायाम् । ६८१ जूष च । ६८२ भूष अलंकारे । ६८३ ऊष रुजायाम् । ६८४ ईष उञ्छे । ६८५ कष ६८६ खष ६८७ शिष ६८८ जष ६८९ झष ६९० शष ६९१ वष ६९२ मष ६९३ रुष ६९४ रिष हिंसार्थाः । ६९५ भष भर्त्सने । ६९६ उष दाहे । ६९७ जिषु ६९८ विषु ६९९ मिषु सेचने । ७०० पुष पुष्टौ । ७०१ श्रिषु ७०२ श्लिषु ७०३ प्रुषु ७०४ प्लुषु दाहे । ७०५ पृषु ७०६ वृषु ७०७ मृषु सेचने ॥ मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च ॥ ७०८

घृषु संघर्षे । ७०९ हृषु अलीके । ७१० तुस ७११ ह्रस ७१२ ह्लस ७१३ रस शब्दे । ७१४ लस श्लेषणक्रीडनयोः ७१५ घस्ऌ अदने । ७१६ जर्ज ७१७ चर्च ७१८ झर्झ परिभाषणहिंसातर्जनेषु । ७१९ पिसृ ७२० पेसृ गतौ । ७२१ हसे हसने । ७२२ णिश समाधौ । ७२३ मिश ७२४ मश शब्दे रोषकृते च । ७२५ शव गतौ । ७२६ शश प्लुतगतौ । ७२७ शसु हिंसायाम् । ७२८ शंसु स्तुतौ ॥ दुर्गतावित्येके । ७२९ चह परिकल्कने । ७३० मह पूजायाम् । ७३१ रह त्यागे । ७३२ रहि गतौ । ७३३ दृह ७३४ दृहि ७३५ बृह ७३६ बृहि वृद्धौ ॥ बृहि शब्दे च । बृहिर् चेत्येके ॥ ७३७ तुहिर् ७३८ दुहिर् ७३९ उहिर् अर्दने । ७४० अर्ह पूजायाम् ॥ घुषिरादय उदात्ता उदात्तेतः परस्मैभाषाः । घसिस्त्वनुदात्तः । ७४१ द्युत दीप्तौ । ७४२ श्विता वर्णे । ७४३ ञिमिदा स्नेहने । ७४४ ञिष्विदा स्नेहनमोचनयोः ॥ मोहनयोरित्येके । ञिक्ष्विदा चेत्येके । ७४५ रुच दीप्तावभिप्रीतौ च । ७४६ घुट परिवर्तने । ७४७ रुट ७४८ लुट ७४९ लुठ प्रतिघाते । ७५० शुभ दीप्तौ । ७५१ क्षुभ संचलने । ७५२ णभ ७५३ तुभ हिंसायाम् ॥ आद्योऽभावेऽपि । ७५४ स्रन्सु ७५५ ध्वन्सु ७५६ भ्रन्सु अवस्रंसने ॥ ध्वन्सु गतौ च । भ्रन्शु इत्यपि केचित् ॥ ७५७ स्रम्भु विश्वासे । ७५८ वृतु वर्तने । ७५९ वृधु वृद्धौ ७६० शृधु शब्दकुत्सायाम् । ७६१ स्यन्दू प्रस्रवणे । ७६२ कृपू सामर्थ्ये ॥ द्युतादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ वृत् ॥ ७६३ घट चेष्टायाम् । ७६४ व्यथ भयसंचलनयोः । ७६५ प्रथ प्रख्याने । ७६६ प्रस विस्तारे । ७६७ म्रद मर्दने । ७६८ स्खद स्खदने । ७६९ क्षजि गतिदानयोः । ७७० दक्ष गतिहिंसनयोः । ७७१ कृप कृपायां गतौ च । ७७२ कदि ७७३ क्रदि ७७४ क्लदि वैक्लव्ये ॥ वैकल्य इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदि क्रदि इदितौ क्रद क्लद इति चानिदितौ इति मैत्रेयः ॥ ७७५ ञित्वरा संभ्रमे ॥ घटादयः षितः । उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ७७६ ज्वर रोगे । ७७७ गड सेचने । ७७८ हेड वेष्टने । ७७९ वट ७८० भट परिभाषणे । ७८१ णट नृत्तौ ॥ गतावित्यन्ये ॥ ७८२ ष्टक प्रतिघाते । ७८३ चक तृप्तौ । ७८४ कखे हसने । ७८५ रगे शङ्कायाम् । ७८६ लगे सङ्गे । ७८७ ह्रगे ७८८ ह्लगे ७८९ षगे ७९० ष्टगे संवरणे । ७९१ कगे नोच्यते । ७९२ अक ७९३ अग कुटिलायां गतौ । ७९४ कण ७९५ रण गतौ । ७९६ चण ७९७ शण ७९८ श्रण दाने च ॥ शण गतावित्यन्ये ॥ ७९९ श्रथ ८०० श्लथ ८०१ क्नथ ८०२ क्लथ हिंसार्थाः । ८०३ वन च । वनु च नोच्यते । ८०४ ज्वल दीप्तौ । ८०५ ह्वल ८०६ ह्मल चलने । ८०७ स्मृ आध्याने । ८०८ दृ भये । ८०९ नॄ नये । ८१० श्रा पाके । मारणतोषणनिशामनेषु ८११ ज्ञा । कम्पने ८१२ चलिः । ८१३ छदिर् ऊर्जने । जिह्वोन्मथने ८१४ लडिः । ८१५ मदी हर्षग्लेपनयोः । ८१६ ध्वन शब्दे । दलि-वलि-स्खलि-रणि-ध्वनि-त्रपि-क्षपयश्चेति भोजः । ८१७ स्वन अवतंसने ॥ घटादयो मितः ॥ जनी-जृष्-क्नसु-रञ्जो-ऽमन्ताश्च । ज्वल-ह्वल-ह्मल-नमामनुपसर्गाद्वा । ग्ला-स्ना-वनु-वमां च । न कमि-अमि-चमाम् । ८१८ शमो दर्शने । ८१९ यमोऽपरिवेषणे । ८२० स्खदिर् अवपरिभ्यां च । ८२१ फण गतौ ॥ घटादयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८२२ राजृ दीप्तौ ॥ उदात्तः स्वरितेदुभयतोभाषः ॥ ८२३ टुभ्राजृ ८२४ टुभ्राशृ ८२५ टुभ्लाशृ दीप्तौ ॥ उदात्ता अनुदात्तेत

आत्मनेभाषाः ॥ ८२६ स्यमु ८२७ स्वन ८२८ ध्वन शब्दे । ८२९ षम ८३० ष्टम अवैकल्ये ॥ वृत् ॥ ८३१ ज्वल दीप्तौ । ८३२ चल कम्पने । ८३३ जल घातने । ८३४ टल ८३५ ट्वल वैक्लव्ये । ८३६ स्थल स्थाने । ८३७ हल विलेखने । ८३८ णल गन्धे ॥ बन्धन इत्येके ॥ ८३९ पल गतौ । ८४० बल प्राणने धान्यावरोधने च । ८४१ पुल महत्त्वे । ८४२ कुल संस्त्याने बन्धुषु च । ८४३ शल ८४४ हुल ८४५ पत्ल गतौ । ८४६ क्वथे निष्पाके । ८४७ पथे गतौ । ८४८ मथे विलोडने । ८४९ ट्वमु उद्गिरणे । ८५० भ्रमु चलने । ८५१ क्षर संचलने ॥ स्यमादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८५२ षह मर्षणे ॥ उदात्तोऽनुदात्तेदात्मनेभाषः ॥ ८५३ रमु क्रीडायाम् ॥ अनुदात्त उदात्तेदात्मनेभाषः ॥ ८५४ षद्लृ विशरणगत्यवसादनेषु । ८५५ शद्लृ शातने । ८५६ क्रुश आह्वाने रोदने च ॥ षदादयस्त्रयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ८५७ कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । ८५८ बुध अवगमने । ८५९ रुह बीजजन्मनि प्रादुर्भावे च । ८६० कस गतौ ॥ वृत् ॥ कुचादय उदात्ता उदात्तेतः परस्मैभाषाः । रुहिस्त्वनुदात्तः ॥ ८६१ हिक्क अव्यक्ते शब्दे । ८६२ अन्चु गतौ याचने च ॥ अचु इत्येके । अचि इत्यपरे ॥ ८६३ टुयाचृ याच्ञायाम् । ८६४ रेटृ परिभाषणे । ८६५ चते ८६६ चदे याचने । ८६७ प्रोथृ पर्याप्तौ । ८६८ मिदृ ८६९ मेदृ मेधाहिंसनयोः ॥ थान्ताविमाविति स्वामी । धान्ताविति न्यासः ॥ ८७० मेधृ संगमे च । ८७१ णिदृ ८७२ णेदृ कुत्सासंनिकर्षयोः । ८७३ शृधु ८७४ मृधु उन्दने । ८७५ बुधिर् बोधने । ८७६ उबुन्दिर् निशामने । ८७७ वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु ॥ नान्तोऽप्ययम् ॥ ८७८ खनु अवदारणे । ८७९ चीवृ आदानसंवरणयोः । ८८० चायृ पूजानिशामनयोः । ८८१ व्यय गतौ । ८८२ दाशृ दाने । ८८३ भेषृ भये ॥ गतावित्येके ॥ ८८४ भ्रेषृ ८८५ भ्लेषृ गतौ । ८८६ अस गतिदीप्त्यादानेषु ॥ अष इत्येके ॥ ८८७ स्पश बाधनस्पर्शनयोः । ८८८ लष कान्तौ । ८८९ चष भक्षणे । ८९० छष हिंसायाम् । ८९१ झष आदानसंवरणयोः । ८९२ भ्रक्ष ८९३ भ्लक्ष अदने । ८९४ दासृ दाने । ८९५ माह माने । ८९६ गुहू संवरणे ॥ हिक्कादय उदात्ताः स्वरितेत उभयतोभाषाः ॥ ८९७ श्रिञ् सेवायाम् ॥ उदात्त उभयतोभाषः ॥ ८९८ भृञ् भरणे । ८९९ हृञ् हरणे । ९०० धृञ् धारणे । ९०१ णीञ् प्रापणे ॥ भृञादयश्चत्वारोऽनुदात्ता उभयतोभाषाः ॥ ९०२ धेट् पाने । ९०३ ग्लै ९०४ म्लै हर्षक्षये । ९०५ द्यै न्यक्करणे । ९०६ द्रै स्वप्ने । ९०७ ध्रै तृप्तौ । ९०८ ध्यै चिन्तायाम् । ९०९ रै शब्दे । ९१० स्त्यै ९११ ष्ट्यै शब्दसंघातयोः । ९१२ खै खदने । ९१३ क्षै ९१४ जै ९१५ षै क्षये । ९१६ कै ९१७ गै शब्दे । ९१८ शै ९१९ श्रै पाके । ९२० पै ९२१ ओवै शोषणे । ९२२ ष्टै वेष्टने । ९२३ ष्णै वेष्टने ॥ शोभायां चेत्येके ॥ ९२४ दैप् शोधने । ९२५ पा पाने । ९२६ घ्रा गन्धोपादाने । ९२७ ध्मा शब्दाग्निसंयोगयोः । ९२८ ष्ठा गतिनिवृत्तौ । ९२९ म्ना अभ्यासे । ९३० दाण् दाने । ९३१ ह्वृ कौटिल्ये । ९३२ स्वृ शब्दोपतापयोः । ९३३ स्मृ चिन्तायाम् । ९३४ ह्वृ संवरणे । ९३५ सृ गतौ । ९३६ ऋ गतिप्रापणयोः । ९३७ गृ ९३८ घृ सेचने । ९३९ ध्वृ हूर्च्छने । ९४० स्रु गतौ । ९४१ षु प्रसवैश्वर्ययोः । ९४२ श्रु श्रवणे । ९४३ ध्रु स्थैर्ये । ९४४ दु ९४५ द्रु गतौ । ९४६ जि ९४७ ज्रि अभिभवे ॥ धेडादयोऽनुदात्ताः

परस्मैभाषाः ॥ ९४८ ष्मिङ् ईषद्धसने । ९४९ गुङ् अव्यक्ते शब्दे । ९५० गाङ् गतौ । ९५१ कुङ् ९५२ घुङ् ९५३ उङ् ९५४ ङुङ् शब्दे ॥ उङ् कुङ् खुङ् गुङ् घुङ् ङुङ् इत्यन्ये ॥ ९५५ च्युङ् ९५६ ज्युङ् ९५७ प्रुङ् ९५८ प्लुङ् गतौ ॥ क्रुङ् इत्येके ॥ ९५९ रुङ् गतिरेषणयोः । ९६० धृङ् अवध्वंसने । ९६१ मेङ् प्रणिदाने । ९६२ देङ् रक्षणे । ९६३ श्यैङ् गतौ । ९६४ प्यैङ् वृद्धौ । ९६५ त्रैङ् पालने ॥ ष्मिङादयोऽनुदात्ता आत्मनेभाषाः ॥ ९६६ पूङ् पवने । ९६७ मूङ् बन्धने । ९६८ डीङ् विहायसा गतौ ॥ पूङादयस्त्रय उदात्ता आत्मनेभाषाः ॥ ९६९ तॄ प्लवनतरणयोः ॥ उदात्तः परस्मैभाषः ॥ ९७० गुप गोपने । ९७१ तिज निशाने । ९७२ मान पूजायाम् । ९७३ बध बन्धने ॥ गुपादयश्चत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ९७४ रभ राभस्ये । ९७५ डुलभष् प्राप्तौ । ९७६ ष्वञ्ज परिष्वङ्गे । ९७७ हद पुरीषोत्सर्गे ॥ रभादयश्चत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ९७८ ञिष्विदा अव्यक्ते शब्दे ॥ उदात्त उदात्तेत् परस्मैभाषः ॥ ९७९ स्कन्दिर् गतिशोषणयोः । ९८० यभ मैथुने । ९८१ णम प्रह्वत्वे शब्दे च । ९८२ गम्लृ ९८३ सृप्लृ गतौ । ९८४ यम उपरमे । ९८५ तप संतापे । ९८६ त्यज हानौ । ९८७ षञ्ज सङ्गे । ९८८ दृशिर् प्रेक्षणे । ९८९ दन्श दशने । ९९० कृष विलेखने । ९९१ दह भस्मीकरणे । ९९२ मिह सेचने ॥ स्कन्दादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ९९३ कित निवासे रोगापनयने च ॥ उदात्तेत् परस्मैभाषः ॥ ९९४ दान खण्डने । ९९५ शान तेजने ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ ९९६ डुपचष् पाके । ९९७ षच समवाये । ९९८ भज सेवायाम् । ९९९ रन्ज रागे । १००० शप आक्रोशे । १००१ त्विष दीप्तौ । १००२ यज देवपूजासंगतिकरणदानेषु । १००३ डुवप् बीजसंताने । छेदनेऽपि । १००४ वह प्रापणे ॥ पचादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः । षचिस्तूदात्तः ॥ १००५ वस निवासे ॥ अनुदात्त उदात्तेत् परस्मैभाषः ॥ १००६ वेञ् तन्तुसंताने । १००७ व्येञ् संवरणे । १००८ ह्वेञ् स्पर्धायां शब्दे च ॥ वेञादयस्त्रयोऽनुदात्ता उभयतोभाषाः ॥ १००९ वद व्यक्तायां वाचि । १०१० टुओश्वि गतिवृद्ध्योः ॥ वृत् । अयं वदतिश्चोदात्तौ परस्मैभाषौ ॥ इति शब्विकरणा भ्वादयः ॥ १ ॥

१०११ अद भक्षणे । १०१२ हन हिंसागत्योः ॥ अनुदात्तावुदात्तेतौ परस्मैपदिनौ ॥ १०१३ द्विष अप्रीतौ । १०१४ दुह प्रपूरणे । १०१५ दिह उपचये । १०१६ लिह आस्वादने ॥ द्विषादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ १०१७ चक्षिङ् व्यक्तायां वाचि । दर्शनेऽपि ॥ अनुदात्तोऽनुदात्तेदात्मनेपदी ॥ १०१८ ईर गतौ कम्पने च । १०१९ ईड स्तुतौ । १०२० ईश ऐश्वर्ये । १०२१ आस उपवेशने । १०२२ आङ्शासु इच्छायाम् । १०२३ वस आच्छादने । १०२४ कासि गतिशासनयोः ॥ कस इत्येके । कश इत्यपि ॥ १०२५ णिसि चुम्बने । १०२६ णिजि शुद्धौ । १०२७ शिजि अव्यक्ते शब्दे । १०२८ पिजि वर्णे ॥ संपर्चन इत्येके । उभयत्रेत्यन्ये । अवयव इत्येके । अव्यक्ते शब्द इतीतरे । पृजि इत्येके ॥ १०२९ वृजी वर्जने ॥ वृजि इत्यन्ये ॥ १०३० पृची संपर्चने ॥ ईरादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ १०३१ षूङ् प्राणिगर्भविमोचने । १०३२ शीङ् स्वप्ने ॥ उदात्तावात्मनेभाषौ । १०३३ यु मिश्रणेऽमिश्रणे च । १०३४ रु शब्दे । १०३५ णु स्तुतौ । १०३६ टुक्षु शब्दे ।

१०३७ क्ष्णु तेजने । १०३८ ष्णु प्रस्रवणे ॥ युप्रभृतय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १०३९ ऊर्णुञ् आच्छादने ॥ उदात्त उभयतोभाषः ॥ १०४० द्यु अभिगमने । १०४१ षु प्रसवैश्वर्ययोः । १०४२ कु शब्दे । १०४३ ष्टुञ् स्तुतौ ॥ द्युप्रभृतयोऽनुदात्ताः परस्मैभाषाः । स्तौतिस्तूभयतोभाषः ॥ १०४४ ब्रूञ् व्यक्तायां वाचि ॥ उदात्त उभयतोभाषः ॥ १०४५ इण् गतौ । १०४६ इङ् अध्ययने । १०४७ इक् स्मरणे । १०४८ वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । १०४९ या प्रापणे । १०५० वा गतिगन्धनयोः १०५१ भा दीप्तौ । १०५२ ष्णा शौचे । १०५३ श्रा पाके । १०५४ द्रा कुत्सायां गतौ । १०५५ प्सा भक्षणे । १०५६ पा रक्षणे । १०५७ रा दाने । १०५८ ला आदाने ॥ द्वावपि दान इति चन्द्रः ॥ १०५९ दाप् लवने । १०६० ख्या प्रकथने १०६१ प्रा पूरणे । १०६२ मा माने । १०६३ वच परिभाषणे ॥ इण्प्रभृतयोऽनुदात्ताः परस्मैभाषाः । इङ् त्वात्मनेपदी ॥ १०६४ विद ज्ञाने । १०६५ अस भुवि । १०६६ मृजू शुद्धौ । १०६७ रुदिर् अश्रुविमोचने ॥ विदादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १०६८ ञिष्वप् शये ॥ उदात्तः परस्मैभाषः । १०६९ श्वस प्राणने । १०७० अन च । १०७१ जक्ष भक्षहसनयोः ॥ वृत् ॥ १०७२ जागृ निद्राक्षये । १०७३ दरिद्रा दुर्गतौ । १०७४ चकासृ दीप्तौ । १०७५ शासु अनुशिष्टौ ॥ श्वसादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १०७६ दीधीङ् दीप्तिदेवनयोः । १०७७ वेवीङ् वेतिना तुल्ये ॥ उदात्तावात्मनेभाषौ ॥ १०७८ षस १०७९ सस्ति स्वप्ने । १०८० वश कान्तौ ॥ षसादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १०८१ चर्करीतं च । १०८२ ह्नुङ् अपनयने ॥ अनुदात्ता आत्मनेभाषाः ॥ इति लुग्विकरणा अदादयः ॥ २ ॥

१०८३ हु दानादानयोः ॥ आदाने चेत्येके ॥ १०८४ ञिभी भये । १०८५ ह्री लज्जायाम् ॥ जुहोत्यादयोऽनुदात्ताः परस्मैभाषाः ॥ १०८६ पॄ पालनपूरणयोः ॥ पृ इत्येके ॥ उदात्तः परस्मैभाषः ॥ १०८७ डुभृञ् धारणपोषणयोः ॥ अनुदात्त उभयतोभाषः ॥ १०८८ माङ् माने शब्दे च । १०८९ ओहाङ् गतौ ॥ अनुदात्तावात्मनेपदिनौ ॥ १०९० ओहाक् त्यागे ॥ अनुदात्तः परस्मैपदी ॥ १०९१ डुदाञ् दाने ॥ १०९२ डुधाञ् धारणपोषणयोः ॥ दान इत्यप्येके ॥ अनुदात्तावुभयतोभाषौ ॥ १०९३ णिजिर् शौचपोषणयोः । १०९४ विजिर् पृथग्भावे । १०९५ विष्लृ व्याप्तौ ॥ णिजिरादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ १०९६ घृ क्षरणदीप्त्योः । १०९७ हृ प्रसह्यकरणे । १०९८ ऋ १०९९ सृ गतौ ॥ घृप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ ११०० भस भर्त्सनदीप्त्योः ॥ उदात्त उदात्तेत् परस्मैपदी ॥ ११०१ कि ज्ञाने ॥ अनुदात्तः परस्मैपदी ॥ ११०२ तुर त्वरणे । ११०३ धिष शब्दे । ११०४ धन धान्ये । ११०५ जन जनने ॥ तुरादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ११०६ गा स्तुतौ ॥ अनुदात्तः परस्मैभाषः । घृप्रभृतय एकादश च्छन्दसि । इयर्ति भाषायामपि ॥ इति श्लुविकरणा जुहोत्यादयः ॥ ३ ॥

११०७ दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु । ११०८ षिवु तन्तुसंताने । ११०९ स्रिवु गतिशोषणयोः १११० ष्ठिवु निरसने । ११११ ष्णुसु अदने ॥ आदान इत्येके । अदर्शन इत्यपरे ॥ १११२ ष्णसु निरसने । १११३ क्नसु ह्वरणदीप्त्योः । १११४ व्युष दाहे । १११५ प्लुष च । १११६ नृती गात्रविक्षेपे । १११७ त्रसी उद्वेगे । १११८

कुथ पूतीभावे । ११११९ पुथ हिंसायाम् । ११२० गुध परिवेष्टने । ११२१ क्षिप प्रेरणे । ११२२ पुष्प विकसने । ११२३ तिम ११२४ ष्टिम ११२५ ष्टीम आर्द्रीभावे । ११२६ व्रीड चोदने लज्जायां च । ११२७ इष गतौ । ११२८ षह ११२९ षुह चक्यर्थे । ११३० जॄष् ११३१ झॄष् वयोहानौ ॥ दिवादय उदात्ता उदात्तेतः परस्मैभाषाः । क्षिपिस्त्वनुदात्तः ॥ ११३२ षूङ् प्राणिप्रसवे । ११३३ दूङ् परितापे ॥ उदात्तावात्मनेभाषौ ॥ ११३४ दीङ् क्षये । ११३५ डीङ् विहायसा गतौ । ११३६ धीङ् आधारे । ११३७ मीङ् हिंसायाम् । ११३८ रीङ् श्रवणे । ११३९ लीङ् श्लेषणे । ११४० व्रीङ् वृणोत्यर्थे ॥ वृत् । स्वादय ओदितः ॥ ११४१ पीङ् पाने । ११४२ माङ् माने । ११४३ ईङ् गतौ । ११४४ प्रीङ् प्रीतौ ॥ दीङादय आत्मनेपदिनोऽनुदात्ताः । डीङ् तूदात्तः ॥ ११४५ शो तनूकरणे । ११४६ छो छेदने । ११४७ षो अन्तकर्मणि । ११४८ दो अवखण्डने ॥ श्यतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ ११४९ जनी प्रादुर्भावे । ११५० दीपी दीप्तौ । ११५१ पूरी आप्यायने । ११५२ तूरी गतित्वरणहिंसनयोः । ११५३ धूरी ११५४ गूरी हिंसागत्योः । ११५५ घूरी ११५६ जूरी हिंसावयोहान्योः । ११५७ शूरी हिंसास्तम्भनयोः । ११५८ चूरी दाहे । ११५९ तप ऐश्वर्ये वा । ११६० वृतु वरणे । ११६१ क्लिश उपतापे । ११६२ काशृ दीप्तौ । ११६३ वाशृ शब्दे ॥ जन्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः । तपिस्त्वनुदात्तः ॥ ११६४ मृष तितिक्षायाम् । ११६५ ११६६ शुचिर् पूतीभावे ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ ११६७ णह बन्धने । ११६८ रन्ज रागे । ११६९ शप आक्रोशे ॥ णहादयस्त्रयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ ११७० पद गतौ । ११७१ खिद दैन्ये । ११७२ विद सत्तायाम् । ११७३ बुध अवगमने । ११७४ युध संप्रहारे । ११७५ अनोरुध कामे । ११७६ अण प्राणने ॥ अन इत्येके ॥ ११७७ मन ज्ञाने । ११७८ युज समाधौ । ११७९ सृज विसर्गे । ११८० लिश अल्पीभावे ॥ पदादयोऽनुदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ११८१ राधोऽकर्मकाद्वृद्धावेव । ११८२ व्यध ताडने । ११८३ पुष पुष्टौ । ११८४ शुष शोषणे । ११८५ तुष प्रीतौ । ११८६ दुष वैकृत्ये । ११८७ श्लिष आलिङ्गने । ११८८ शक विभाषितो मर्षणे । ११८९ ष्विदा गात्रप्रक्षरणे ॥ ११९० क्रुध क्रोधे । ११९१ क्षुध बुभुक्षायाम् । ११९२ शुध शौचे । ११९३ षिधु संराद्धौ ॥ राधादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ ११९४ रध हिंसासंराद्ध्योः । ११९५ णश अदर्शने । ११९६ तृप प्रीणने । ११९७ दृप हर्षमोहनयोः । ११९८ द्रुह जिघांसायाम् ११९९ मुह वैचित्त्ये । १२०० ष्णुह उद्गिरणे । १२०१ ष्णिह प्रीतौ ॥ वृत् । रधादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १२०२ शमु उपशमे । १२०३ तमु काङ्क्षायाम् । १२०४ दमु उपशमे । १२०५ श्रमु तपसि खेदे च । १२०६ भ्रमु अनवस्थाने । १२०७ क्षमू सहने । १२०८ क्लमु ग्लानौ । १२०९ मदी हर्षे ॥ वृत् ॥ १२१० असु क्षेपणे । १२११ यसु प्रयत्ने । १२१२ जसु मोक्षणे । १२१३ तसु उपक्षये । १२१४ दसु च । १२१५ वसु स्तम्भे । १२१६ व्युष विभागे ॥ व्युस इत्यन्ये । युस इत्यपरे ॥ १२१७ प्लुष दाहे । १२१८ विस प्रेरणे । १२१९ कुस संश्लेषणे । १२२० बुस उत्सर्गे । १२२१ मुस खण्डने । १२२२ मसी परिणामे ॥ समी इत्येके ॥ १२२३ लुठ विलोडने । १२२४ उच समवाये । १२२५ भृशु १२२६ भ्रन्शु अधःपतने । १२२७ वृश वरणे । १२२८ कृश तनूकरणे । १२२९ ञितृष पिपासायाम् । १२३०

हृष तुष्टौ । १२३१ रुष १२३२ रिष हिंसायाम् । १२३३ डिप क्षेपे । १२३४ कुप क्रोधे । १२३५ गुप व्याकुलत्वे । १२३६ युपु १२३७ रुपु १२३८ लुपु विमोहने । १२३९ लुभ गार्ध्ये । १२४० क्षुभ संचलने । १२४१ णभ १२४२ तुभ हिंसायाम् ॥ क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते ॥ १२४३ क्लिद आर्द्रीभावे । १२४४ ञिमिदा स्नेहने । १२४५ ञिक्ष्विदा स्नेहनमोचनयोः । १२४६ ऋधु वृद्धौ । १२४७ गृधु अभिकाङ्क्षायाम् ॥ वृत् । असुप्रभृतय उदात्ता उदात्तेतः परस्मैभाषाः । इति श्यन्विकरणा दिवादयः ॥ ४ ॥

१२४८ षूञ् अभिषवे । १२४९ षिञ् बन्धने । १२५० शिञ् निशाने । १२५१ डुमिञ् प्रक्षेपणे । १२५२ चिञ् चयने । १२५३ स्तृञ् आच्छादने । १२५४ कृञ् हिंसायाम् । १२५५ वृञ वरणे । १२५६ धुञ् कम्पने । धूञ् इत्येके ॥ स्वादयोऽनुदात्ता उभयतोभाषाः । वृञ् उदात्तः ॥ १२५७ टुदु उपतापे । १२५८ हि गतौ वृद्धौ च । १२५९ पृ प्रीतौ । १२६० स्पृ प्रीतिपालनयोः ॥ प्रीतिचलनयोः इत्यन्ये । स्मृ इत्येके ॥ १२६१ आप्लृ व्याप्तौ । १२६२ शक्लृ शक्तौ । १२६३ राध १२६४ साध संसिद्धौ । दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ॥ १२६५ अशू व्याप्तौ संघाते च । १२६६ ष्टिघ आस्कन्दने ॥ अशिस्तिघी उदात्तावनुदात्तेतावात्मनेभाषौ ॥ १२६७ तिक १२६८ तिग गतौ च । १२६९ षघ हिंसायाम् । १२७० ञिधृषा प्रागल्भ्ये । १२७१ दन्भु दम्भने । १२७२ ऋधु वृद्धौ । तृप प्रीणने इत्येके ॥ छन्दसि ॥ १२७३ अह व्याप्तौ । १२७४ दघ घातने पालने च । १२७५ चमु भक्षणे । १२७६ रि १२७७ क्षि १२७८ चिरि १२७९ जिरि १२८० दाश १२८१ दृ हिंसायाम् ॥ क्षिर् भाषायाम् इत्येके । ऋक्षीत्यजादिरेके । रेफवानित्यन्ये ॥ वृत् । तिकादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ इति श्नुविकरणाः स्वादयः ॥ ५ ॥

१२८२ तुद व्यथने । १२८३ णुद प्रेरणे । १२८४ दिश अतिसर्जने । १२८५ भ्रस्ज पाके । १२८६ क्षिप प्रेरणे १२८७ कृष विलेखने ॥ तुदादयोऽनुदात्ता स्वरितेत उभयतोभाषाः ॥ १२८८ ऋषी गतौ ॥ उदात्त उदात्तेत्परस्मैपदी ॥ १२८९ जुषी प्रीतिसेवनयोः । १२९० ओविजी भयचलनयोः । १२९१ ओलजी १२९२ ओलस्जी व्रीडने ॥ जुषादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ १२९३ ओव्रश्चू छेदने । १२९४ व्यच व्याजीकरणे । १२९५ उछि उञ्छे । १२९६ उछी विवासे । १२९७ ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु । १२९८ मिछ उत्क्लेशे । १२९९ जर्ज १३०० चर्च १३०१ झर्झ परिभाषणभर्त्सनयोः । १३०२ त्वच संवरणे । १३०३ ऋच स्तुतौ । १३०४ उब्ज आर्जवे । १३०५ उज्झ उत्सर्गे । १३०६ लुभ विमोहने । १३०७ रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ॥ रिह इत्येके ॥ १३०८ तृप १३०९ तृन्फ तृप्तौ ॥ द्वावपि फान्तावित्येके ॥ १३१० तुप १३११ तुन्प १३१२ तुफ १३१३ तुन्फ हिंसायाम् । १३१४ दृप १३१५ दृन्फ उत्क्लेशे ॥ प्रथमोऽपि द्वितीयान्त इत्येके ॥ १३१६ ऋफ १३१७ ऋन्फ हिंसायाम् । १३१८ गुफ १३१९ गुन्फ ग्रन्थे । १३२० उभ १३२१ उन्भ पूरणे । १३२२ शुभ १३२३ शुन्भ शोभार्थे । १३२४ दृभी ग्रन्थे । १३२५ चृती हिंसाग्रन्थनयोः । १३२६ विध विधाने । १३२७ जुड गतौ ॥ जुन इत्येके ॥ १३२८ मृड सुखने । १३२९ पृड च । १३३० पृण प्रीणने । १३३१ वृण च । १३३२ मृण हिंसायाम् । १३३३ तुण कौटिल्ये । १३३४ पुण कर्मणि शुभे । १३३५ मुण प्रतिज्ञाने ॥ १३३६ कुण शब्दोपकरणयोः ।

१३३७ शुन गतौ । १३३८ द्रुण हिंसागतिकौटिल्येषु । १३३९ घुण १३४० घूर्ण भ्रमणे । १३४१ षुर ऐश्वर्यदीप्त्योः । १३४२ कुर शब्दे । १३४३ खुर छेदने । १३४४ मुर संवेष्टने १३४५ क्षुर विलेखने । १३४६ घुर भीमार्थशब्दयोः । १३४७ पुर अग्रगमने । १३४८ वृहू उद्यमने ॥ बृहू इत्यन्ये ॥ १३४९ तृहू १३५० स्तृहू १३५१ तृन्हू हिंसार्थाः । १३५२ इष इच्छायाम् । १३५३ मिष स्पर्धायाम् । १३५४ किल श्वैत्यक्रीडनयोः । १३५५ तिल स्नेहे । १३५६ चिल वसने । १३५७ चल विलसने । १३५८ इल स्वप्नक्षेपणयोः । १३५९ विल संवरणे । १३६० बिल भेदने । १३६१ णिल गहने । १३६२ हिल भावकरणे । १३६३ शिल १३६४ षिल उञ्छे । १३६५ मिल श्लेषणे । १३६६ लिख अक्षरविन्यासे । १३६७ कुट कौटिल्ये । १३६८ पुट संश्लेषणे । १३६९ कुच संकोचने । १३७० गुज शब्दे । १३७१ गुड रक्षायाम् । १३७२ डिप क्षेपे । १३७३ छुर छेदने । १३७४ स्फुट विकसने । १३७५ मुट आक्षेपमर्दनयोः । १३७६ त्रुट छेदने । १३७७ तुट कलहकर्मणि । १३७८ चुट १३७९ छुट छेदने । १३८० जुट बन्धने । १३८१ कड मदे । १३८२ लुट संश्लेषणे । १३८३ कृड घनत्वे । १३८४ कुड बाल्ये । १३८५ पुड उत्सर्गे । १३८६ घुट प्रतिघाते । १३८७ तुड तोडने । १३८८ थुड १३८९ स्थुड संवरणे ॥ खुड छुड इत्येके ॥ १३९० स्फुर १३९१ फुल संचलने ॥ स्फुर स्फुरणे स्फुल संचलने इत्येके । स्फर इत्यन्ये ॥ १३९२ स्फुड १३९३ चुड १३९४ व्रुड संवरणे ॥ १३९५ क्रुड १३९६ भृड निमज्जन इत्येके ॥ अथाद्य उदात्ता उदात्तेतः परस्मैभाषाः ॥ १३९७ गुरी उद्यमने ॥ उदात्तोऽनुदात्तेदात्मनेपदी ॥ १३९८ णू स्तवने । १३९९ धू विधूनने ॥ उदात्तौ परस्मैभाषौ ॥ १४०० गु पुरीषोत्सर्गे । १४०१ ध्रु गतिस्थैर्ययोः ॥ ध्रुव इत्येके ॥ अनुदात्तौ परस्मैपदिनौ ॥ १४०२ कुङ् शब्दे ॥ उदात्त आत्मनेपदी ॥ दीर्घान्त इति कैयटादयः । ह्रस्वान्त इति न्यासः ॥ वृत् ॥ १४०३ पृङ् व्यायामे । १४०४ मृङ् प्राणत्यागे ॥ अनुदात्तावात्मनेभाषौ ॥ १४०५ रि १४०६ पि गतौ । १४०७ धि धारणे । १४०८ क्षि निवासगत्योः ॥ रियत्यादयोऽनुदात्ताः परस्मैभाषाः ॥ १४०९ षू प्रेरणे । १४१० कॄ विक्षेपे । १४११ गॄ निगरणे ॥ उदात्ताः परस्मैभाषाः ॥ १४१२ दृङ् आदरे । १४१३ धृङ् अवस्थाने ॥ अनुदात्तावात्मनेभाषौ ॥ १४१४ प्रच्छ ज्ञीप्सायाम् ॥ वृत् ॥ १४१५ सृज विसर्गे । १४१६ टुमस्जो शुद्धौ । १४१७ रुजो भङ्गे । १४१८ भुजो कौटिल्ये । १४१९ छुप स्पर्शे । १४२० रुश १४२१ रिश हिंसायाम् । १४२२ लिश गतौ । १४२३ स्पृश संस्पर्शने । १४२४ विच्छ गतौ । १४२५ विश प्रवेशने । १४२६ मृश आमर्शने । १४२७ णुद प्रेरणे । १४२८ षद्लृ विशरणगत्यवसादनेषु । १४२९ शद्लृ शातने ॥ पृच्छत्यादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ विच्छस्तूदात्तः ॥ १४३० मिल संगमे ॥ उदात्तः स्वरितेदुभयतभाषः ॥ १४३१ मुच्लृ मोक्षणे । १४३२ लुप्लृ छेदने । १४३३ विद्लृ लाभे । १४३४ लिप उपदेहे । १४३५ षिच क्षरणे ॥ मुचादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः । विन्दतिस्तूदात्तः ॥ १४३६ कृती छेदने ॥ उदात्त उदात्तेत्परस्मैपदी ॥ १४३७ खिद परिघाते ॥ अनुदात्त उदात्तेत्परस्मैपदी ॥ १४३८ पिश अवयवे ॥ उदात्त उदात्तेत्परस्मैपदी ॥ वृत् ॥ इति शविकरणास्तुदादयः ॥ ६ ॥

१४३९ रुधिर् आवरणे । १४४० भिदिर् विदारणे । १४४१ छिदिर् द्वैधीकरणे । १४४२

रिचिर् विरेचने । १४४३ विचिर् पृथग्भावे । १४४४ क्षुदिर् संपेषणे । १४४५ युजिर् योगे ॥ रुधादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ १४४६ उछृदिर् दीप्तिदेवनयोः । १४४७ उतृदिर् हिंसानादरयोः ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ १४४८ कृती वेष्टने ॥ उदात्त उदात्तेत्परस्मैपदी ॥ १४४९ ञिइन्धी दीप्तौ ॥ उदात्तोऽनुदात्तेदात्मनेपदी ॥ १४५० खिद दैन्ये । १४५१ विद विचारणे ॥ अनुदात्तावनुदात्तेतावात्मनेपदिनौ ॥ १४५२ शिष्लृ विशेषणे । १४५३ पिष्लृ संचूर्णने । १४५४ भञ्जो आमर्दने । १४५५ भुज पालनाभ्यवहारयोः ॥ शिषादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ १४५६ तृह १४५७ हिंसि हिंसायाम् । १४५८ उन्दी क्लेदने । १४५९ अन्जू व्यक्तिम्रक्षणकान्तिगतिषु । १४६० तन्चु संकोचने । १४६१ ओविजी भयचलनयोः । १४६२ वृजी वर्जने । १४६३ पृची संपर्के ॥ तृहादय उदात्ता उदात्तेतः परस्मैपदिनः ॥ वृत् ॥ इति श्नम्विकरणा रुधादयः ॥ ७ ॥

१४६४ तनु विस्तारे । १४६५ षणु दाने । १४६६ क्षणु हिंसायाम् । १४६७ क्षिणु च । १४६८ ऋणु गतौ । १४६९ तृणु अदने । १४७० घृणु दीप्तौ ॥ तनादय उदात्ताः स्वरितेत उभयतोभाषाः ॥ १४७१ वनु याचने । १४७२ मनु अवबोधने ॥ उदात्तावनुदात्तेतावात्मनेभाषौ ॥ १४७३ डुकृञ् करणे ॥ अनुदात्त उभयतोभाषः ॥ इत्युविकरणास्तनादयः ॥ ८ ॥

१४७४ डुक्रीञ् द्रव्यविनिमये । १४७५ प्रीञ् तर्पणे कान्तौ च । १४७६ श्रीञ् पाके । १४७७ मीञ् हिंसायाम् । १४७८ षिञ् बन्धने । १४७९ स्कुञ् आप्रवणे । १४८० युञ् बन्धने ॥ क्र्यादयोऽनुदात्ता उभयतोभाषाः ॥ १४८१ क्नूञ् शब्दे । १४८२ द्रूञ् हिंसायाम् । १४८३ पूञ् पवने । १४८४ लूञ् छेदने । १४८५ स्तृञ् आच्छादने । १४८६ कॄञ् हिंसायाम् । १४८७ वृञ् वरणे । १४८८ धूञ् कम्पने ॥ क्नूप्रभृतय उदात्ता उभयतोभाषाः ॥ १४८९ शॄ हिंसायाम् । १४९० पॄ पालनपूरणयोः । १४९१ वॄ वरणे ॥ भरण इत्येके ॥ १४९२ भॄ भर्त्सने । १४९३ मॄ हिंसायाम् । १४९४ दॄ विदारणे । १४९५ जॄ वयोहानौ ॥ झॄ इत्येके । धॄ इत्यन्ये । १४९६ नॄ नये । १४९७ कॄ हिंसायाम् । १४९८ ॠ गतौ । १४९९ गॄ शब्दे ॥ शॄणातिप्रभृतय उदात्ता उदात्तेतः परस्मैपदिनः ॥ १५०० ज्या वयोहानौ । १५०१ री गतिरेषणयोः । १५०२ ली श्लेषणे । १५०३ व्ली वरणे । १५०४ प्ली गतौ ॥ वृत् ॥ १५०५ व्री वरणे । १५०६ भ्री भये ॥ भर इत्येके ॥ १५०७ क्षीष् हिंसायाम् । १५०८ ज्ञा अवबोधने । १५०९ बन्ध बन्धने ॥ ज्यादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ १५१० वृङ् संभक्तौ ॥ उदात्त आत्मनेपदी ॥ १५११ श्रन्थ विमोचनप्रतिहर्षयोः । १५१२ मन्थ विलोडने । १५१३ श्रन्थ १५१४ ग्रन्थ संदर्भे । १५१५ कुन्थ संश्लेषणे ॥ संक्लेश इत्येके ॥ कुथ इति दुर्गः ॥ १५१६ मृद क्षोदे । १५१७ मृड च ॥ अयं सुखेऽपि ॥ १५१८ गुध रोषे । १५१९ कुष निष्कर्षे । १५२० क्षुभ संचलने । १५२१ णभ १५२२ तुभ हिंसायाम् । १५२३ क्लिशू विबाधने । १५२४ अश भोजने । १५२५ उध्रस उञ्छे । १५२६ इष आभीक्ष्ण्ये । १५२७ विष विप्रयोगे । १५२८ प्रुष १५२९ प्लुष स्नेहनसेवनपूरणेषु । १५३० पुष पुष्टौ । १५३१ मुष स्तेये । १५३२ खच भूतप्रादुर्भावे ॥ वान्तोऽयमित्येके ॥ १५३३ हेठ च ॥ श्रन्थादय उदात्ता उदात्तेतो विषिवर्जं परस्मैभाषाः ॥ १५३४ ग्रह उपादाने ॥ उदात्तः स्वरितेदुभयतोभाषः ॥ इति श्नाविकरणाः क्र्यादयः ॥ ९ ॥

१५३५ चुर स्तेये । १५३६ चिति स्मृत्याम् । १५३७ यत्रि संकोचे । १५३८ स्फुडि परिहासे ॥

स्फुटि इत्यपि ॥ १५३९लक्ष दर्शनाङ्कनयोः । १५४०कुद्रि अनृतभाषणे । १५४१ लड उपसेवायाम् । १५४२ मिदि स्नेहने । १५४३ ओलडि उत्क्षेपणे ॥ ओकारो धात्ववयव इत्येके । न इत्यपरे । उलडि इत्यन्ये ॥ १५४४ जल अपवारणे ॥ लज इत्येके ॥ १५४५ पीड अवगाहने । १५४६ नट अवस्यन्दने । १५४७ श्रथ प्रयत्ने ॥ प्रस्थान इत्येके ॥ १५४८ बध संयमने ॥ बन्ध इति चान्द्राः ॥ १५४९ पॄ पूरणे । १५५० ऊर्ज बलप्राणनयोः । १५५१ पक्ष परिग्रहे । १५५२ वर्ण १५५३ चूर्ण प्रेरणे ॥ वर्ण वर्णन इत्येके ॥ १५५४ प्रथ प्रख्याने ।१५५५ पृथ प्रक्षेपे ॥ पथ इत्येके ॥ १५५६ षम्ब संबन्धने । १५५७ शम्ब च ॥ साम्ब इत्येके ॥ १५५८ भक्ष अदने । १५५९ कुट्ट छेदनभर्त्सनयोः ॥ पूरण इत्येके ॥ १५६० पुट्ट १५६१ चुट्ट अल्पीभावे । १५६२अट्ट १५६३ षुट्ट अनादरे । १५६४ लुण्ट स्तेये । १५६५ शठ १५६६ श्वठ असंस्कारगत्योः ॥ श्वठि इत्येके ॥ १५६७ तुजि १५६८ पिजि हिंसाबलादाननिकेतनेषु ॥ तुज पिज इति केचित् । लजि लुजि इत्येके ॥ १५६९ पिस गतौ । १५७० षान्त्व सामप्रयोगे ॥ १५७१ श्वल्क १५७२ वल्क परिभाषणे । १५७३ ष्णिह स्नेहने ॥ स्फिट इत्येके ॥ १५७४ स्मिट अनादरे । ष्मिङ् इत्येके ॥ १५७५ श्लिष श्लेषणे । १५७६ पथि गतौ । १५७७ पिछ कुट्टने । १५७८ छदि संवरणे । १५७९ श्रण दाने । १५८० तड आघाते । १५८१ खड १५८२ खडि १५८३ कडि भेदने । १५८४ कुडि रक्षणे । १५८५ गुडि वेष्टने ॥ रक्षण इत्येके । कुठि इत्यन्ये । गुठि इत्यपरे ॥ १५८६ खुडि खण्डने । १५८७ वटि विभाजने ॥ वडि इति केचित् ॥ १५८८ मडि भूषायां हर्षे च । १५८९ भडि कल्याणे । १५९० छर्द वमने । १५९१ पुस्त १५९२ बुस्त आदरानादरयोः । १५९३ चुद संचोदने । १५९४ नक्क १५९५ धक्क नाशने । १५९६ चक्क १५९७ चुक्क व्यथने । १५९८ क्षल शौचकर्मणि । १५९९ तल प्रतिष्ठायाम् । १६०० तुल उन्माने । १६०१ दुल उत्क्षेपे । १६०२ पुल महत्त्वे । १६०३ चुल समुच्छ्राये । १६०४ मूल रोहणे । १६०५ कल १६०६ विल क्षेपे । १६०७ बिल भेदने । १६०८ तिल स्नेहने । १६०९ चल भृतौ । १६१० पाल रक्षणे । १६११ लूष हिंसायाम् । १६१२ शुल्ब माने । १६१३ शूर्प च । १६१४ चुट छेदने । १६१५ मुट संचूर्णने । १६१६ पडि १६१७ पासि नाशने । १६१८ व्रज मार्गसंस्कारगत्योः । १६१९ शुल्क अतिस्पर्शने । १६२० चपि गत्याम् । १६२१ क्षपि क्षान्त्याम् । १६२२ छजि कृच्छ्रजीवने । १६२३ श्वर्त गत्याम् । १६२४ श्वभ्र च । १६२५ ज्ञप ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु ॥ मिच्चेत्येके ॥ १६२६ यम च परिवेषणे । १६२७ चह परिकल्कने चप इत्येके ॥ १६२८ रह त्यागे च । १६२९ बल प्राणने । १६३० चिञ् चयने ॥ नान्ये मितोऽहेतौ ॥ १६३१ घट्ट चलने । १६३२ मुस्त संघाते । १६३३ खट्ट संवरणे । १६३४ षट्ट १६३५ स्फिट्ट १६३६ चुबि हिंसायाम् । १६३७ पुल संघाते ॥ पूर्ण इत्येके । पुण इत्यन्ये ॥ १६३८ पुंस अभिवर्धने । १६३९ टकि बन्धने । १६४० धूस कान्तिकरणे ॥ मूर्धन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥ १६४१ कीट वर्णे । १६४२ चूर्ण संकोचने । १६४३ पूज पूजायाम् । १६४४ अर्क स्तवने ॥ तपन इत्येके ॥ १६४५ शुठ आलस्ये । १६४६ शुठि शोषणे । १६४७ जुड प्रेरणे । १६४८ गज १६४९ मार्ज शब्दार्थौ । १६५० मर्च च । १६५१ घृ प्रस्रवणे ॥ स्रावण इत्येके ॥ १६५२ पचि विस्तारवचने । १६५३ तिज निशाने । १६५४ कृत

संशब्दने । १६५५ वर्ध छेदनपूरणयोः । १६५६ कुबि आच्छादने ॥ कुभि इत्येके ॥ १६५७ लुबि १६५८ तुबि अर्दने ॥ अर्दन इत्येके ॥ १६५९ ह्लप व्यक्तायां वाचि ॥ क्लप इत्येके ॥ १६६० चुटि छेदने । १६६१ इल प्रेरणे । १६६२ म्रक्ष म्लेच्छने । १६६३ म्लेच्छ अव्यक्तायां वाचि ॥ १६६४ ब्रूस १६६५ बर्ह हिंसायाम् ॥ केचिदिह गर्ज गर्द शब्दे गर्ध अभिकाङ्क्षायाम् इति पठन्ति ॥ १६६६ गुर्द पूर्वनिकेतने । १६६७ जसि रक्षणे ॥ मोक्षण इति केचित् ॥ १६६८ ईड स्तुतौ । १६६९ जसु हिंसायाम् । १६७० पिडि संघाते । १६७१ रुष रोषे ॥ रुट इत्येके ॥ १६७२ डिप क्षेपे । १६७३ ष्टुप समुच्छ्राये ॥ आकुस्मादात्मनेपदिनः ॥ १६७४ चित संचेतने । १६७५ दशि दंशने । १६७६ दसि दर्शनदंशनयोः ॥ दस इत्यप्येके ॥ १६७७ डप १६७८ डिप संघाते । १६७९ तत्रि कुटुम्बधारणे । १६८० मत्रि गुप्तपरिभाषणे । १६८१ स्पश ग्रहणसंश्लेषणयोः । १६८२ तर्ज १६८३ भर्त्स तर्जने । १६८४ वस्त १६८५ गन्ध अर्दने । १६८६ विष्क हिंसायाम् ॥ हिष्क इत्येके ॥ १६८७ निष्क परिमाणे । १६८८ लल ईप्सायाम् । १६८९ कूण संकोचे । १६९० तूण पूरणे । १६९१ भ्रूण आशाविशङ्कयोः । १६९२ शठ श्लाघायाम् । १६९३ यक्ष पूजायाम् । १६९४ स्यम वितर्के । १६९५ गूर उद्यमने । १६९६ शम १६९७ लक्ष आलोचने । १६९८ कुत्स अवक्षेपणे । १६९९ त्रुट छेदने ॥ कुट इत्येके ॥ १७०० गल स्रवणे । १७०१ भल आभण्डने । १७०२ कूट आप्रदाने ॥ अवसादन इत्येके ॥ १७०३ कुट्ट प्रतापने । १७०४ वञ्चु प्रलम्भने । १७०५ वृष शक्तिबन्धने । १७०६ मद तृप्तियोगे । १७०७ दिवु परिकूजने । १७०८ गॄ विज्ञाने । १७०९ विद चेतनाख्यानविवासेषु । १७१० मान स्तम्भे । १७११ यु जुगुप्सायाम् । १७१२ कुस्म नाम्नो वा कुत्सितस्मयने ॥ इत्याकुस्मीयाः ॥ १७१३ चर्च अध्ययने । १७१४ बुक्क भाषणे । १७१५ शब्द उपसर्गादाविष्कारे च ॥ १७१६ कण निमीलने । १७१७ जभि नाशने । १७१८ षूद क्षरणे । १७१९ जसु ताडने । १७२० पश बन्धने । १७२१ अम रोगे । १७२२ चट १७२३ स्फुट भेदने । १७२४ घट संघाते । हन्त्यर्थाश्च । १७२५ दिवु मर्दने । १७२६ अर्ज प्रतियत्ने । १७२७ घुषिर् विशब्दने । १७२८ आङः क्रन्द सातत्ये । १७२९ लस शिल्पयोगे । १७३० तसि १७३१ भूष अलंकरणे । १७३२ अर्ह पूजायाम् । १७३३ ज्ञा नियोगे । १७३४ भज विश्राणने । १७३५ शृधु प्रसहने । १७३६ यत निकारोपस्कारयोः । १७३७ रक १७३८ लग आस्वादने ॥ रघ इत्येके । रग इत्यन्ये ॥ १७३९ अञ्चु विशेषणे । १७४० लिगि चित्रीकरणे । १७४१ मुद संसर्गे । १७४२ त्रस धारणे ॥ ग्रहण इत्येके । वारण इत्यन्ये ॥ १७४३ उध्रस उञ्छे ॥ उकारो धात्ववयव इत्येके । न इत्यन्ये । १७४४ मुच प्रमोचने मोदने च । १७४५ वस स्नेहछेदापहरणेषु । १७४६ चर संशये । १७४७ च्यु सहने ॥ हसने चेत्येके । च्युस इत्येके ॥ १७४८ भुवोऽवकल्कने । १७४९ कृपेश्च ॥ आ स्वदः सकर्मकात् ॥ १७५० ग्रस ग्रहणे । १७५१ पुष धारणे । १७५२ दल विदारणे । १७५३ पट १७५४ पुट १७५५ लुट १७५६ तुजि १७५७ मिजि १७५८ पिजि १७५९ लुजि १७६० भजि १७६१ लघि १७६२ त्रसि १७६३ पिसि १७६४ कुसि १७६५ दशि १७६६ कुशि १७६७ घट १७६८ घटि १७६९ बृहि १७७० बर्ह १७७१ बल्ह १७७२ गुप १७७३ धूप १७७४ विच्छ १७७५ चीव १७७६ पुथ १७७७ लोकृ १७७८ लोचृ १७७९ णद १७८० कुप १७८१ तर्क १७८२ वृतु १७८३

वृधु भाषार्थाः । १७८४ रुट १७८५ लजि १७८६ अजि १७८७ दसि १७८८ भृशि १७८९ रुशि १७९० शीक १७९१ रुसि १७९२ नट १७९३ पुटि १७९४ जि १७९५ चि १७९६ रघि १७९७ लघि १७९८ अहि १७९९ रहि १८०० महि च । १८०१ लडि १८०२ तड १८०३ नल च । १८०४ पूरी आप्यायने । १८०५ रुज हिंसायाम् । १८०६ ष्वद आस्वादने ॥ स्वाद इत्येके ॥ आ धृषाद्वा ॥ १८०७ युज १८०८ पृच संयमने । १८०९ अर्च पूजायाम् । १८१० षह १८११ ईर क्षेपे । १८१२ ली द्रवीकरणे । १८१३ वृजी वर्जने । १८१४ वृञ् आवरणे मर्षणे । १८१५ जॄ वयोहानौ । १८१६ ज्रि च । १८१७ रिच वियोजनसंपर्चनयोः । १८१८ शिष असर्वोपयोगे । १८१९ तप दाहे । १८२० तृप तृप्तौ ॥ संदीपन इत्येके ॥ १८२१ छृदी संदीपने ॥ चृप छृप दृप संदीपन इत्येके ॥ १८२२ दृभी भये । १८२३ दृभ संदर्भे । १८२४ श्रथ मोक्षणे ॥ हिंसायाम् इत्यन्ये ॥ १८२५ मी गतौ । १८२६ ग्रन्थ बन्धने । १८२७ शीक आमर्षणे । १८२८ चीक च । १८२९ अर्द हिंसायाम् ॥ स्वरितेत् ॥ १८३० हिंसि हिंसायाम् । १८३१ अर्ह पूजायाम् । १८३२ आङः-षद पद्यर्थे । १८३३ शुन्ध शौचकर्मणि । १८३४ छद अपवारणे ॥ स्वरितेत् ॥ १८३५ जुष परितर्कणे ॥ परितर्पण इत्यन्ये ॥ १८३६ धूञ् कम्पने । १८३७ प्रीञ् तर्पणे । १८३८ श्रन्थ १८३९ ग्रन्थ संदर्भे । १८४० आपॢ लम्भने ॥ स्वरितेदयमित्येके ॥ १८४१ तनु श्रद्धोपकरणयोः ॥ उपसर्गाच्च दैर्घ्ये ॥ चन श्रद्धोपहननयोरित्येके ॥ १८४२ वद संदेशवचने ॥ स्वरितेत् । अनुदात्तेदित्येके ॥ १८४३ वच परिभाषणे । १८४४ मान पूजायाम् । १८४५ भू प्राप्तावात्मनेपदी ॥ १८४६ गर्ह विन्दने । १८४७ मार्ग अन्वेषणे । १८४८ कठि शोके । १८४९ मृजू शौचालंकारयोः । १८५० मृष तितिक्षायाम् ॥ स्वरितेत् ॥ १८५१ धृष प्रसहने ॥ इत्याधृषीयाः ॥ अथादन्ताः ॥ १८५२ कथ वाक्यप्रबन्धे । १८५३ वर ईप्सायाम् । १८५४ गण संख्याने । १८५५ शठ १८५६ श्वठ सम्यगवभाषणे । १८५७ पट १८५८ वट ग्रन्थे । १८५९ रह त्यागे । १८६० स्तन १८६१ गदी देवशब्दे । १८६२ पत गतौ वा ॥ वा अदन्त इत्येके ॥ १८६३ पष अनुपसर्गात् । १८६४ स्वर आक्षेपे । १८६५ रच प्रतियत्ने । १८६६ कल गतौ संख्याने च । १८६७ चह परिकल्कने । १८६८ मह पूजायाम् । १८६९ सार १८७० कृप १८७१ श्रथ दौर्बल्ये । १८७२ स्पृह ईप्सायाम् । १८७३ भाम क्रोधे । १८७४ सूच पैशुन्ये । १८७५ खेट भक्षणे ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ॥ १८७६ क्षोट क्षेपे । १८७७ गोम उपलेपने । १८७८ कुमार क्रीडायाम् । १८७९ शील उपधारणे । १८८० साम सान्त्वप्रयोगे । १८८१ वेल कालोपदेशे । काल इति पृथग्धातुरित्येके ॥ १८८२ पल्यूल लवनपवनयोः । १८८३ वात सुखसेवनयोः ॥ गति सुखसेवनयोरित्येके ॥ १८८४ गवेष मार्गणे । १८८५ वास उपसेवायाम् । १८८६ निवास आच्छादने । १८८७ भाज पृथक्कर्मणि । १८८८ सभाज प्रीतिदर्शनयोः ॥ प्रीतिसेवनयोरित्येके ॥ १८८९ ऊन परिहाणे । १८९० ध्वन शब्दे । १८९१ कूट परितापे ॥ परिदाह इत्यन्ये ॥ १८९२ सङ्केत १८९३ ग्राम १८९४ कुण १८९५ गुण चामन्त्रणे । १८९६ केत श्रावणे निमन्त्रणे च । १८९७ कुण संकोचनेऽपि । १८९८ स्तेन चौर्ये । आगर्वादात्मनेपदिनः ॥ १८९९ पद गतौ । १९०० गृह ग्रहणे । १९०१ मृग अन्वेषणे । १९०२ कुह विस्मापने । १९०३ शूर १९०४ वीर विक्रान्तौ । १९०५ स्थूल परिबृंहणे । १९०६ अर्थ उपयाच्ञायाम् । १९०७

सत्र संतानक्रियायाम्। १९०८ गर्व माने ॥ इत्यागर्वीयाः ॥ १९०९ सूत्र वेष्टने। १९१० मूत्र प्रस्रवणे। १९११ रूक्ष पारुष्ये। १९१२ पार १९१३ तीर कर्मसमाप्तौ। १९१४ पुट संसर्गे। १९१५ धेक दर्शन इत्येके। १९१६ कत्र शैथिल्ये ॥ कर्त इत्यप्येके ॥ 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (ग १८६)। 'तत्करोति तदाचष्टे' (गं १८७)। 'तेनातिक्रामति' (ग १८८)। 'धातुरूपं च' (ग १८९)। 'आख्यानात्कृतस्तदाचष्टेकृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्' (वा १७६८)। 'कर्तृकरणाद्धात्वर्थे' (ग १९०)। १९१७ वल्क दर्शने। १९१८ चित्र चित्रीकरणे ॥ कदाचिद्दर्शने ॥ १९१९ अंस समाघाते। १९२० वट विभाजने। १९२१ लज प्रकाशने ॥ वटि लजि इत्येके ॥ १९२२ मिश्र संपर्के १९२३ सङ्ग्राम युद्धे ॥ अनुदात्तेत् ॥ १९२४ स्तोम श्लाघायाम्। १९२५ छिद्र कर्णभेदने ॥ करणभेदन इत्येके। कर्ण इति धात्वन्तरमित्यपरे ॥ १९२६ अन्ध दृष्ट्युपघाते ॥ उपसंहार इत्यन्ये ॥ १९२७ दण्ड दण्डनिपातने १९२८। अङ्क पदे लक्षणे च। १९२९ अङ्ग च। १९३० सुख १९३१ दुःख तत्क्रियायाम् ॥ १९३२ रस आस्वादनस्नेहनयोः। १९३३ व्यय वित्तसमुत्सर्गे। १९३४ रूप रूपक्रियायाम्। १९३५ छेद द्वैधीकरणे। १९३६ छद अपवारणे। १९३७ लाभ प्रेरणे। १९३८ व्रण गात्रविचूर्णने। १९३९ वर्ण वर्णक्रियाविस्तारगुणवचनेषु ॥ बहुलमेतन्निदर्शनम् ॥ १९४० पर्ण हरितभावे। १९४१ विष्क दर्शने। १९४२ क्षप प्रेरणे १९४३ वस निवासे। १९४४ तुत्थ आवरणे ॥ णिङ्ङ्गान्निरसने। श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च। पुच्छादिषु प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम् ॥ इति स्वार्थणिजन्ताश्चुरादयः ॥ १० ॥

इति श्रीपाणिनिमुनिप्रणीतो धातुपाठः समाप्तः।

---

(४) पाणिनीयं लिङ्गानुशासनम्।

१ लिङ्गम्। २ स्त्री। ३ ऋकारान्ता मातृदुहितृस्वसृयातृननन्दरः। ४ अन्यूप्रत्ययान्तो धातुः। ५ अशनिभरण्यरणयः पुंसि च। ६ मिन्यन्तः। ७ वह्निवृष्ण्यग्नयः पुंसि। ८ श्रोणियोन्यूर्मयः पुंसि च। ९ क्तिन्नन्तः। १० ईकारान्तश्च। ११ ऊङाबन्तश्च। १२ य्वन्तमेकाक्षरम्। १३ विंशत्यादिरा नवतेः। १४ दुन्दुभिरक्षेषु। १५ नाभिरक्षत्रिये। १६ उभावन्यत्र पुंसि। १७ तलन्तः। १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि। १९ यादो नपुंसकम्। २० भास्स्रुक्स्रग्दिग्दृगुष्णिगुपानहः। २१ स्थूणोर्णे नपुंसके च। २२ गृहशशाभ्यां क्लीबे। २३ प्रावृड्विप्रुड्रुट्तृड्विट्त्विषः। २४ दर्विविदिवेदिखनिशाण्यश्रिवेशिकृष्योषधिकट्यङ्गुलयः। २५ तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः। २६ शष्कुलिराजिकुट्यशनिवर्तिभ्रुकुटित्रुटिवलिपङ्क्तयः। २७ प्रतिपदापद्विपत्संपच्छरत्संसत्परिषदुषःसंवित्क्षुत्पुन्मुत्समिधः। २८ आशीर्धूःपूर्गीर्द्वारः। २९ अप्सुमनस्समासिकतावर्षाणां बहुत्वं च। ३० स्रक्त्वग्ज्योग्वाग्यवागूनौस्फिचः। ३१ तटिसीमासंवध्याः। ३२ चूल्लिवेणिखार्यश्च। ३३ ताराधाराज्योत्स्नादयश्च। शलाका स्त्रियां नित्यम् ॥

३४ पुमान् । ३५ घञबन्तः । ३६ घाजन्तश्च । ३७ भयलिङ्गभगपदानि नपुंसके । ३८ नङन्तः । ३९ याच्ञा स्त्रियाम् । ४० क्यन्तो घुः । ४१ इषुधिः स्त्री च । ४२ देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि । ४३ त्रिविष्टपत्रिभुवने नपुंसके । ४४ द्यौः स्त्रियाम् । ४५ इषुबाहू स्त्रियां च । ४६ बाणकाण्डौ नपुंसके च । ४७ नन्तः । ४८ क्रतुपुरुषकपोलगुल्फमेघाभिधानानि । ४९ अभ्रं नपुंसकम् । ५० उकारान्तः । ५१ धेनुरज्जुकुहूसरयूतनुरेणुप्रियङ्गवः स्त्रियाम् । ५२ समासे रज्जुः पुंसि च । ५३ श्मश्रुजानुस्वाद्वश्रुजतुत्रपुतालूनि नपुंसके । ५४ वसु चार्थवाचि । ५५ मद्गुमधुशीधुसानुकमण्डलूनि नपुंसके च । ५६ रुत्वन्तः । ५७ दारुकसेरुजत्रुवस्तुमस्तूनि नपुंसके । ५८ सक्तुर्नपुंसके च । ५९ प्राग्रश्मेरकारान्तः । ६० कोपधः । ६१ चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके । ६२ कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डककटकदण्डकपिटकतालकफलककल्कपुलाकानि नपुंसके च । ६३ टोपधः । ६४ किरीटमुकुटललाटवटवीटशृङ्गाटकरटलोष्टानि नपुंसके । ६५ कुटकूटकपटकपाटकर्पटनटनिकटकीटकटानि नपुंसके च । ६६ णोपधः । ६७ ऋणलवणपर्णतोरणरणोष्णानि नपुंसके । ६८ कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसके च । ६९ थोपधः । ७० काष्ठपृष्ठरिक्थोक्थानि नपुंसके । ७१ काष्ठा दिगर्था स्त्रियाम् । ७२ तीर्थप्रोथयूथगाथानि नपुंसके च । ७३ नोपधः । ७४ जघनाजिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके । ७५ मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसंमानभवनवसनसंभावनविभावनविमानानि नपुंसके च । ७६ पोपधः । ७७ पापरूपोडुपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके । ७८ शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च । ७९ भोपधः । ८० तलभं नपुंसकम् । ८१ जृम्भं नपुंसके च । ८२ मोपधः । ८३ रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके । ८४ सङ्ग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च । ८५ योपधः । ८६ किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । ८७ गोमयकषायमलयान्वयाव्ययानि नपुंसके च । ८८ रोपधः । ८९ द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रच्छिद्रनारतीरदूरकृच्छ्ररन्ध्राश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदरशरीरकन्दरमन्दरपञ्जराजरजठराजिरवैरचामरपुष्करगह्वरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रक्षेत्रक्षत्रमित्रकलत्रच्छत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रमलत्रास्त्रशस्त्रशास्त्रवस्त्रपत्रपात्रनक्षत्राणि नपुंसके । ९० शुक्रमदेवतायाम् । ९१ चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च । ९२ षोपधः । ९३ शिरीषर्जीषाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके । ९४ यूषकरीषमिषविषवर्षाणि नपुंसके च । ९५ सोपधः । ९६ पानसबिसबुससाहसानि नपुंसके । ९७ चमससरसनिर्यासोपवासकर्पासवासमासकासकांसमांसानि नपुंसके च । ९८ कंसं च प्राणिनि । ९९ रश्मिदिवसाभिधानानि । १०० दीधितिः स्त्रियाम् । १०१ दिनाहनी नपुंसके । १०२ मानाभिधानानि । १०३ द्रोणाढकौ नपुंसके च । १०४ खारीमानिके स्त्रियाम् । १०५ दाराक्षतलाजासूनां बहुत्वं च । १०६ नाड्यपजनोपपदानि व्रणाङ्गपदानि । १०७ मरुद्गरुदुत्तरदृत्विजः । १०८ ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकपिमुनयः । १०९ ध्वजगजमुञ्जपुञ्जाः । ११०

हस्तकुन्तान्तवातव्रातदन्तधूर्तसूतचूतमुहूर्ताः १११ षण्डमण्डकरण्डभरण्डरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः । ११२ वंशांशपुरोडाशाः । ११३ ह्रदकन्दकुन्दबुद्बुदशब्दाः । ११४ अर्घपथिमथ्यृभुक्षिस्तम्बनितम्बपूगाः । ११५ पल्लवपल्वलकफरेफकटाहनिर्व्यूहमठमणितरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्गपुङ्खाः । ११६ सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः ॥

११७ नपुंसकम् । ११८ भावे ल्युडन्तः । ११९ निष्ठा च । १२० त्वष्यञौ तद्धितौ । १२१ कर्मणि च ब्राह्मणादिगुणवचनेभ्यः । १२२ यद्यढग्यगञ्ण्वुञ्छाश्च भावकर्मणि । १२३ द्वन्द्वैकत्वम् । १२४ अभाषायां हेमन्तशिशिरावहोरात्रे च । १२५ अनञ्कर्मधारयस्तत्पुरुषः । १२६ अनल्पे छाया । १२७ राजामनुष्यपूर्वा सभा । १२८ सुरासेनाच्छायाशालानिशाः स्त्रियां च । १२९ परवत् । १३० अपथपुण्याहे नपुंसके । १३१ संख्यापूर्वा रात्रिः । १३२ द्विगुः स्त्रियां च । १३३ इसुसन्तः । १३४ अर्चिः स्त्रियां च । १३५ छदिः स्त्रियामेव । १३६ मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि । १३७ सीरार्थोदनाः पुंसि । १३८ वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । १३९ अटवी स्त्रियाम् । १४० लोपधः । १४१ तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि । १४२ शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालबालनिगलपलालबिडालखिलशूलाः पुंसि च । १४३ शतादिसंख्या । १४४ शतायुतप्रयुताः पुंसि च । १४५ लक्षाकोटी स्त्रियाम् । १४६ सहस्रः पुंसि च । १४७ मन्व्यच्कोऽकर्तरि । १४८ ब्रह्मन्पुंसि च । १४९ नामरोमणी नपुंसके । १५० असन्तो द्व्यच्कः । १५१ अप्सराः स्त्रियाम् । १५२ त्रान्तः । १५३ यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव । १५४ भृत्रामित्रच्छात्रपुत्रमन्त्रवृत्रमेत्राः पुंसि । १५५ पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च । १५६ बलकुसुमयुद्धपत्तनरणाभिधानानि । १५७ पद्मकमलोत्पलानि पुंसि च । १५८ आहवसंग्रामौ पुंसि । १५९ आजिः स्त्रियामेव । १६० फलजातिः । १६१ वृक्षजातिः स्त्रियामेव । १६२ वियज्जगत्सकृत्पृषच्छकृद्यकृदुदश्वितः । १६३ नवनीतावतानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि । १६४ श्राद्धकुलिशदैवपीठकुण्डाङ्कदधिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्वबीजानि । १६५ दैवं पुंसि च । १६६ धान्याज्यसस्यरूप्यपण्यवर्ण्यधिष्ण्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि । १६७ द्वन्द्वबर्हदुःखबडिशपिच्छविश्वकुटुम्बकवचवरवृन्दारकाणि । १६८ अक्षमिन्द्रिये ॥

१६९ स्त्रीपुंसयोः । १७० गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः । १७१ मन्युसीधुकर्कन्धुसिन्धुकण्डुरेणवः । १७२ गुणवचनमुकारान्तं नपुंसकं च । १७३ अपत्यार्थतद्धिते ॥

१७४ पुंनपुंसकयोः । १७५ घृतभूतमुस्तक्ष्वेलितैरावतपुस्तबुस्तलोहिताः । १७६ शृङ्गार्घनिदाघोद्यमशल्यदृढाः । १७७ व्रजकुञ्जकुथकूर्चप्रस्थदर्पार्भार्धर्चपुच्छाः । १७८ कबन्धौषधायुधान्ताः । १७९ दण्डमण्डखण्डशवसैन्धवपार्श्वाकाशाङ्कुशकाशकुशकुलिशाः । १८० गृहमेहदेहपट्टपटहाष्टापदार्बुदककुदाश्च ॥

१८१ अवशिष्टलिङ्गम् । १८२ अव्ययं कतियुष्मदस्मदः । १८३ ष्णान्ता संख्या । १८४ गुणवचनं च । १८५ कृत्याश्च १८६ करणाधिकरणयोर्ल्युट् । १८७ सर्वादीनि सर्वनामानि ॥

इति श्रीपाणिनिमुनिप्रणीतं लिङ्गानुशासनं समाप्तम् ।

---

(५) पाणिनीया शिक्षा ।

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥ १ ॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ २ ॥ त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शंभुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥ ३ ॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ ४ ॥ अनुस्वारो विसर्गश्च ᳲकᳲपौ चापि पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो लृकारः प्लुत एव च ॥ ५ ॥ १ ॥ आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ ६ ॥ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । प्रातःसवनयोगं तं छन्दोगायत्रमाश्रितम् ॥ ७ ॥ कण्ठे माध्यंदिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥ ८ ॥ सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ ९ ॥ स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥ १० ॥ २ ॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ ११ ॥ उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ । स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ १२ ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३ ॥ ओभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १४ ॥ यद्योभावप्रसंधानमुकारादि परं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः ॥ १५ ॥ ३ ॥ हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ १६ ॥ कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसाः स्मृताः ॥ १७ ॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजौ स्मृतौ ॥ १८ ॥ अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९ ॥ संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥ २० ॥ ४ ॥ स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥ २१ ॥ अनुस्वारयमानां च नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२ ॥ अलाबुवीणानिर्घोषो दन्त्यमूल्यस्वरानुगः । अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च ॥ २३ ॥ अनुस्वारे विवृत्त्यां तु विरामे चाक्षरद्वये । द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रौकारवकारयोः ॥ २४ ॥ व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ २५ ॥ ५ ॥ यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते । एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ॥ २६ ॥ रङ्गवर्णं प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥ २७ ॥ हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि । नासिकायां तथार्धं च रङ्गस्यैवं द्विमात्रता ॥ २८ ॥ हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरन् । मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम् ॥ २९ ॥ मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत् । स रङ्गं कम्पयेत्कम्पं रथीवेति

निदर्शनम् ॥ ३० ॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः । सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥ ३१ ॥ ६ ॥ गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२ ॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्यं लयसमर्थं च षडेते पाठका गुणाः ॥ ३३ ॥ ॥ शङ्कितं भीतमुद्धुष्टमव्यक्तमनुनासिकम् । काकस्वरं शिरसिगतं तथा स्थानविवर्जितम् ॥ ३४ ॥ उपांशुदष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ॥ ३५ ॥ प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन । मध्यंदिने कण्ठगतेन चैव चक्राह्वसंकूजितसंनिभेन ॥ ३६ ॥ तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥ ३७ ॥ ७ ॥ अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शरः स्मृताः । शेषाः स्पृष्टाः हलः प्रोक्ता निबोधानुप्रदानतः ॥ ३८ ॥ यमोऽनुनासिका नह्नौ नादिनो हझषः स्मृताः । ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः ॥ ३९ ॥ ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते । दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि ॥ ४० ॥ छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ ४१ ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ४२ ॥ ८ ॥ उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा । उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव ॥ ४३ ॥ उदात्तं प्रदेशिनीं विद्यात्प्रचयं मध्यतोऽङ्गुलिम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥ ४४ ॥ अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् । मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥ ४५ ॥ अग्निः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती । अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तं प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ॥ ४६ ॥ हविषां मध्योदात्तं स्वरिति स्वरितम् । बृहस्पतिरिति द्व्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥ ४७ ॥ अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः । स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥ ४८ ॥ ९ ॥ चाषस्तु वदते मात्रां द्विमात्रं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥ ४९ ॥ कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥ ५० ॥ सुतीर्थादागतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् । सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ॥ ५१ ॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ ५२ ॥ अवक्षरं हनायुष्यं विस्वरं व्याधिपीडितम् । अक्षताशस्त्ररूपेण वज्रं पतति मस्तके ॥ ५३ ॥ हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ ५४ ॥ हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥ ५५ ॥ १० ॥ शंकरः शांकरीं प्रादाद्दाक्षीपुत्राय धीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥ ५६ ॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ ५७ ॥ अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ ५८ ॥ त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानतुलं च सुखं समश्नुते दिवीति

दिवीति ॥ ५९ ॥ ११ ॥ अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथा गीत्यचोस्पृष्टोदात्तं चाषस्तु शंकर एकादश ॥

इति श्रीपाणिनीया शिक्षा समाप्ता ।

अष्टकं गणपाठश्च धातुपाठस्तथैव च ।
लिङ्गानुशासनं शिक्षा पाणिनीया अमी क्रमात् ॥

---

(६) कात्यायनप्रणीतो वार्तिकपाठः ।

प्रत्याहारसूत्राणि ।

१ सिद्धे शब्दार्थसंबन्धे । २ लोकतः । ३ लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः ! ४ अस्त्यप्रयुक्तः । ५ अस्त्यप्रयुक्त इति चेन्नार्थे शब्दप्रयोगात् । ६ अप्रयोगः प्रयोगान्यत्वात् । ७ सर्वे देशान्तरे । ८ ज्ञाने धर्म इति चेत्तथाधर्मः । ९ अ चारे नियमः । १० प्रयोगे सर्वलोकस्य । ११ शास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन । १२ सूत्रे व्याकरणे षष्ठ्यर्थोऽनुपपन्नः । १३ शब्दाप्रतिपत्तिः । १४ शब्दे ल्युडर्थः । १५ भवे च तद्धितः । १६ प्रोक्तादयश्च तद्धिताः । १७ लक्ष्यलक्षणे व्याकरणम् । १८ वृत्तिसमवायार्थ उपदेशः । १९ अनुबन्धकरणार्थश्च । २० इष्टबुद्ध्यर्थश्च । २१ इष्टबुद्ध्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानामप्युपदेशः । २२ आकृत्युपदेशात्सिद्धम् । २३ आकृत्युपदेशात्सिद्धमिति चेत्संवृतादीनां प्रतिषेधः । २४ लिङ्गार्था तु प्रत्यापत्तिः ।

अइउण् (प्र १) ॥ २५ अकारस्य विवृतोपदेश आकारग्रहणार्थः । २६ तस्य विवृतोपदेशादन्यत्रापि विवृतोपदेशः सवर्णग्रहणार्थः । २७ दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः । २८ स्थानी प्रकल्पयेदेतावनुस्वारो यथा यणम् । २९ तत्रानुवृत्तिनिर्देशे सवर्णाग्रहणमनण्त्वात् । ३० एकत्वादकारस्य सिद्धम् । ३१ अनुबन्धसंकरस्तु । ३२ एकाजनेकाज्ग्रहणेषु चानुपपत्तिः । ३३ द्रव्यवच्चोपचाराः । ३४ विषयेण तु नानालिङ्गकरणात्सिद्धम् । ३५ एकाजनेकाज्ग्रहणेषु चावृत्तिसंख्यानात् । ३६ आन्यभाव्यं तु कालशब्दव्यवायात् । ३७ युगपच्च देशपृथक्त्वदर्शनात् । ३८ आकृतिग्रहणात्सिद्धम् । ३९ तद्वच्च तपरकरणम् । ४० हल्ग्रहणेषु च । ४१ रूपसामान्याद्वा ।

ऋलृक् (प्र २) ॥ ४२ लृकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः । ४३ न्याय्यभावात्कल्पनं संज्ञादिषु । ४४ अनुकरणं शिष्टाशिष्टाप्रतिषिद्धेषु यथा लौकिकवैदिकेषु । ४५ एकदेशविकृतस्यानन्यत्वात्प्लुत्यादयः । ४६ रवत्प्रतिषेधाच्च ॥

एओङ् । ऐऔच् (प्र ३ । ४) ॥ ४७ संध्यक्षरेषु तपरोपदेशश्चेत्तपरकरणम् । ४८ प्लुत्यादिष्वज्विधिः । ४९ प्लुतसंज्ञा च । ५० अतपर एच इग्घ्रस्वादेशे । ५१ एकादेशे दीर्घग्रहणम् । ५२ वर्णैकदेशा वर्णग्रहणेन चेत्संध्यक्षरे समानाक्षरविधिप्रतिषेधः । ५३ दीर्घे ह्रस्वविधिप्रतिषेधः । ५४ एकवर्णवच्च । ५५ नाव्यपवृक्तस्यावयवे तद्विधिर्यथा द्रव्येषु । ५६ संध्यक्ष-

रेषु विवृतत्वात् । ५७ अग्रहणं चेन्नुड्विधिलादेशविनामेष्वृकारग्रहणम् । ५८ प्लुतावैच इदुतौ । ५९ तुल्यरूपे संयोगे द्विव्यञ्जनविधिः ॥

हयवरट् (प्र ५) ॥ ६० हकारस्य परोपदेशेऽड्ग्रहणेषु हग्रहणम् । ६१ उत्त्वे च । ६२ पूर्वोपदेशे किंत्त्वक्त्वेड्विधयो झल्ग्रहणानि च । ६३ रेफस्य परोपदेशेऽननुनासिकद्विर्वचनपरसवर्णप्रतिषेधः । ६४ पूर्वोपदेशे किंत्त्वप्रतिषेधो व्यलोपवचनं च । ६५ अयोगवाहानामट्सु णत्वम् । ६६ शर्षु जश्भावषत्वे । ६७ अविशेषेण संयोगोपधासंज्ञालोन्त्यद्विर्वचनस्थानिवद्भावप्रतिषेधाः । ६८ अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् । ६९ वर्णव्यत्यये चार्थान्तरगमनात् । ७० वर्णानुपलब्धौ चानर्थगतेः । ७१ संघातार्थवत्त्वाच । ७२ संघातस्वैकार्थ्यात्सुबभावो वर्णात् । ७३ अनर्थकास्तु प्रतिवर्णमर्थानुपलब्धेः । ७४ वर्णव्यत्ययापायोपजनविकारेष्वर्थदर्शनात् । ७५ प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न । ७६ आचारात् । ७७ अप्रधानत्वात् । ७८ लोपश्च बलवत्तरः । ७९ ऊकालोऽजिति वा योगस्तत्कालानां यथा भवेत् । अचां ग्रहणमच्कार्यं तेनैषां न भविष्यति ८० अनुवर्तते विभाषा शरोऽचि यद्वारयत्ययं द्विर्वचनम् । ८१ नित्ये हि तस्य लोपे प्रतिषेधार्थो न कश्चित्स्यात् ॥

लण् (प्र ६) ॥ ८२ सवर्णेऽण् तपरं ह्युकृत् । ८३ व्योरन्यत्र परेणण् स्यात् ॥

ञमङणनम् । झभञ् (प्र ७ । ८) ॥ ८४ अक्षरं न क्षरं विद्यात् । ८५ अश्नोतेर्वा सरोऽक्षरम् । ८६ वर्णं वाहुः पूर्वसूत्रे । ८७ किमर्थमुपदिश्यते । ८८ वर्णज्ञानं वाग्विषयो यत्र च ब्रह्म वर्तते । ८९ तदर्थमिष्टबुद्ध्यर्थं लघ्वर्थं चोपदिश्यते ॥

प्रथमोऽध्यायः ।

१ । १ वृद्धिरादैच् १६ ॥ ९० संज्ञाधिकारः संज्ञाप्रत्ययार्थः । ९१ इतरथा ह्यसंप्रत्ययो यथा लोके । ९२ संज्ञासंज्ञ्यसंदेहश्च । ९३ आचार्याचारात्संज्ञासिद्धिः । ९४ यथा लौकिकवैदिकेषु । ९५ संज्ञासंज्ञ्यसंदेहश्च (सिद्धः) । ९६ अनाकृतिः (संज्ञा) । ९७ लिङ्गेन वा । ९८ सतो वृद्ध्यादिषु संज्ञाभावात्तदाश्रय इतरेतराश्रयत्वादप्रसिद्धिः । ९९ सिद्धं तु नित्यशब्दत्वात् । १०० किमर्थं शास्त्रमिति चेन्निवर्तकत्वात्सिद्धम् । १०१ (प्रत्येकं गुणवृद्धिसंज्ञे भवतः इति वक्तव्यम्) । १०२ अन्यत्र सहवचनात्समुदाये संज्ञाप्रसङ्गः । १०३ प्रत्यवयवं च वाक्यपरिसमाप्तेः । १०४ आकारस्य तपरकरणं सवर्णार्थम् ॥

१ । ३ इको गुणवृद्धी ३४ ॥ १०५ इग्ग्रहणमात्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् । १०६ संज्ञया विधाने नियमः । १०७ वृद्धिगुणावलोऽन्त्यस्येति चेन्मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणम् । १०८ सर्वदेशप्रसङ्गश्चानिगन्तस्य । १०९ इग्मात्रस्येति चेज्जुसिसार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः । ११० पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् । १११ वृद्धिग्रहणमुत्तरार्थम् । ११२ मृज्यर्थमिति चेद्योगविभागात्सिद्धम् । ११३ वृद्धिप्रतिषेधानुपपत्तिस्त्विक्प्रकरणात् । ११४ तस्मादिग्लक्षणा वृद्धिः । ११५ षष्ठ्याः स्थानेयोगत्वादिनिवृत्तिः । ११६ अन्यतरार्थं पुनर्वचनम् । ११७ प्रसारणे च । ११८ विषयार्थं पुनर्वचनम् । ११९ उरण्परे च । १२० सिद्धं तु षष्ठ्यधिकारे वचनात् ॥

१ । ४ न धातुलोप आर्धधातुके २६५६ ॥ १२१ यङ्यक्क्यवलोपे प्रतिषेधः । १२२

तुम्लोपात्त्विन्यनुबन्धलोपेऽप्रतिषेधार्थम् । १२३ इक्प्रकरणाच्छुम्लोपे वृद्धिः । १२४ निपातनात्स्यदादिषु । १२५ प्रत्ययाश्रयत्वादन्यत्र सिद्धम् । १२६ रकि ज्यः संप्रसारणम् । १२७ अल्लोपस्य स्थानिवत्त्वात् । १२८ अनारम्भो वा ॥

१ । ५ क्ङिति च २२१७ ॥ १२९ क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् । १३० उपधा रोरवीत्यर्थम् । १३१ शचङन्तस्यान्तरङ्गलक्षणत्वात् । १३२ तद्धितकाम्योरिक्प्रकरणात् । १३३ लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्गः । १३४ लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनात्सिद्धम् ॥

१ । ६ दीधीवेवीटाम् २१९० ॥ १३५ दीधीवेव्योश्छन्दोविषयत्वाद्दृष्टानुविधित्वाच्च छन्दसोऽदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः । १३६ दीध्यदिति च श्यन् व्यत्ययेन ॥

१ । ७ हलोऽनन्तराः संयोगः ३० ॥ १३७ संयोगसंज्ञायां सहवचनं यथान्यत्र । १३८ समुदाये संयोगादिलोपो मस्जेः । १३९ द्वयोर्हलोः संयोग इति चेद्द्विर्वचनम् । १४० न वाज्विधेः । १४१ स्वरानन्तर्हितवचनम् । १४२ दृष्टमानन्तर्यं व्यवहितेऽपि । १४३ आनन्तर्यवचनं किमर्थमिति चेदेकप्रतिषेधार्थम् । १४४ न वातज्जातीयकव्यवायात् ॥

१ । ९ तुल्यास्यप्रयत्नं सवर्णम् १० ॥ १४५ सवर्णसंज्ञायां भिन्नदेशेष्वतिप्रसङ्गः प्रयत्नसाम्यात् । १४६ सिद्धं त्वास्ये तुल्यदेशप्रयत्नं सवर्णम् । १४७ तस्य । १४८ तस्यावचनं वचनप्रामाण्यात् । १४९ संबन्धिशब्दैर्वा तुल्यम् । १५० ऋकारलकारयोः सवर्णविधिः ॥

१ । १० नाज्झलौ १३ ॥ १५१ अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वात् । १५२ तत्र सवर्णलोपे दोषः । १५३ सिद्धमनच्त्वात् । १५४ वाक्यापरिसमाप्तेर्वा ॥

१ । ११ ईदूदेद्द्विवचनं प्रगृह्यम् १०० ॥ १५५ ईदादयो द्विवचनं प्रगृह्या इति चेदन्त्यस्य विधिः । १५६ ईदाद्यन्तमिति चेदेकस्य विधिः । १५७ न वाद्यन्तवत्त्वात् । १५८ ईदाद्यन्तं द्विवचनान्तमिति चेल्लुकि प्रतिषेधः । १५९ सप्तम्यामर्थग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधस्य ॥

१ । १२ अदसो मात् १०१ ॥ १६० मात्प्रगृह्यसंज्ञायां तस्यादयावेकादेशप्रतिषेधः । १६१ वचनार्थौ हि सिद्धे । १६२ विप्रतिषेधाद्वा । १६३ आश्रयात्सिद्धत्वं च यथा रोरुत्वे । १६४ असिद्धे ह्युत्व आदुणाप्रसिद्धिः । १६५ तत्र साकि दोषः । १६६ न वा ग्रहणविशेषणत्वात् ॥

१ । १३ शे १०२ ॥ १६७ शेऽर्थवद्ग्रहणात् ॥

१ । १५ ओत् १०४ ॥ १६८ ओतश्च्विप्रतिषेधः ॥

१ । १७ उञः १०६ ॥ १६९ उञ इति योगविभागः ॥

१ । १८ ऊँ १०७ ॥ १७० ऊँ वा शाकल्यस्य ॥

१ । १९ ईदूतौ च सप्तम्यर्थे १०९ ॥ १७१ ईदूतौ सप्तमीत्येव । १७२ लुप्तेऽर्थग्रहणाद्भवेत् । १७३ पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते । १७४ वचनाद्यत्र दीर्घत्वम् । १७५ तत्रापि सरसी यदि । १७६ ज्ञापकं स्यात्तदन्तत्वे । १७७ मा वा पूर्वपदस्य भूत् ॥

१ । २० दाधा घ्वदाप् २३७३ ॥ १७८ घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम् । ('–शिद्विकृतार्थम्' इति भारद्वाजीयपाठः) । १७९ समानशब्दप्रतिषेधः । १८० समानशब्दाप्रतिषेधोऽर्थवद्ग्रहणात् । १८१ अनुपसर्गाद्वा । १८२ न वार्थवतो ह्यागमस्तद्गुणीभूतस्तद्ग्रहणेन गृह्यते

यथान्यत्र । १८३ दीङः प्रतिषेधः स्थाघ्वोरित्त्वे । १८४ दाप्प्रतिषेधे न दैप्यनेजन्तत्वात् । १८५ सिद्धमनुबन्धस्यानेकान्तत्वात् । १८६ पित्प्रतिषेधाद्वा ॥

१ । २१ आद्यन्तवदेकस्मिन् ३४८ ॥ १८७ सत्यन्यस्मिन्नाद्यन्तवद्भावादेकस्मिन्नाद्यन्तवद्वचनम् । १८८ तत्र व्यपदेशिवद्वचनम् । १८९ एकाचो द्वे प्रथमार्थम् । १९० षत्वे चादेशसंप्रत्ययार्थम् । १९१ अवचनाल्लोकविज्ञानात्सिद्धम् । १९२ अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन् । १९३ आदिवत्त्वे प्रयोजनं प्रत्ययाग्निदाद्युदात्तत्वे । १९४ वलादेरार्धधातुकस्येट् । १९५ यस्मिन्विधिस्तदादित्वे । १९६ अजाद्याट्त्वे । १९७ अन्तवद्द्विवचनान्तप्रगृह्य १९८ मिदचोऽन्त्यात्परः । १९९ अचोऽन्त्यादि टि । २०० अलोऽन्त्यस्य । २०१ येन विधिस्तदन्तत्वे ॥

१ । २२ तरप्तमपौ घः २००३ ॥ २०२ घसंज्ञायां नदीतरे प्रतिषेधः । २०३ घसंज्ञायां नदीतरेऽप्रतिषेधः । २०४ तरब्ग्रहणं ह्यौपदेशिकम् ॥

१ । २३ बहुगणवतुडति संख्या २९८ ॥ २०५ संख्यासंज्ञायां संख्याग्रहणम् । २०६ संख्यासंप्रत्ययार्थम् । २०७ इतरथा ह्यसंप्रत्ययोऽकृत्रिमत्वाद्यथा लोके । २०८ उत्तरार्थं च । २०९ अध्यर्धग्रहणं च समासकन्विध्यर्थम् । २१० लुकि चाग्रहणम् । २११ अर्धपूर्वपदश्च पूरणप्रत्ययान्तः । २१२ अधिकग्रहणं चालुकि समासोत्तरपदवृद्ध्यर्थम् । २१३ बहुव्रीहौ चाग्रहणम् । २१४ बह्वादीनामग्रहणम् ॥

१ । २४ ष्णान्ता षट् ३६९ ॥ २१५ षट्संज्ञायामुपदेशवचनम् । २१६ शतादिष्टनोर्नुट्प्रतिषेधार्थम् ॥

१ । २६ क्तक्तवतू निष्ठा ३०१२ ॥ २१७ निष्ठासंज्ञायां समानशब्दप्रतिषेधः । २१८ निष्ठासंज्ञायां समानशब्दाप्रतिषेधः । २१९ अनुबन्धोऽन्यत्वकरः । २२० अनुबन्धोऽन्यत्वकर इति चेन्न लोपात् । २२१ सिद्धविपर्यासश्च । २२२ कारककालविशेषात्सिद्धम् । २२३ लुङि सिजादिदर्शनात् ॥

१ । २७ सर्वादीनि सर्वनामानि २१३ ॥ २२४ सर्वनामसंज्ञायां निपातनाण्णत्वाभावः । २२५ संज्ञोपसर्जनप्रतिषेधः । २२६ पाठात्पर्युदासः पठितानां संज्ञाकरणम् । २२७ सर्वाद्यानन्तर्यकार्यार्थम् । २२८ प्रयोजनं डतरादीनामद्भावे । २२९ त्यदादिविधौ च । २३० उभस्य सर्वनामत्वेऽकजर्थः । २३१ अन्याभावो द्विवचनटाब्विषयत्वात् । २३२ उभयोऽन्यत्र । २३३ अवचनादापि तत्परविज्ञानमिति चेत्केऽपि तुल्यम् । २३४ भवतोऽकच्छेषात्वानि ॥

१ २९ न बहुव्रीहौ २२२ ॥ २३५ प्रतिषेधे भूतपूर्वस्योपसंख्यानम् । २३६ प्रतिषेधे भूतपूर्वस्योपसंख्यानानर्थक्यं पूर्वादीनां व्यवस्थायामिति वचनात् ॥

१ । ३४ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् २१८ ॥ २३७ अवरादीनां च पुनः सूत्रपाठे ग्रहणानर्थक्यं गणे पठितत्वात् ॥

१ । ३६ अन्तरं बहिर्योगोपसंव्यानयोः २२० ॥ २३८ उपसंव्यानग्रहणमनर्थकं बहिर्योगेण कृतत्वात् । २३९ न वा शाटकयुगाद्यर्थम् । २४० अपुरीति वक्तव्यम् ('गणसूत्र एतत्कर्तव्यम्' इति कैयटः) । २४१ वाप्रकरणे तीयस्य ङित्सूपसंख्यानम् ॥

१ । ३८ तद्धितश्चासर्वविभक्तिः ४४८ ॥ २४२ असर्वविभक्तावविभक्तिनिमित्तस्योपसं-

ख्यानम् । २४३ सर्वविभक्तिर्ह्यविशेषात् । २४४ बह्वादीनां चोपसंख्यानम् । २४५ अविभक्त्या-वितरेतराश्रयत्वादप्रसिद्धिः । २४६ अलिङ्गमसंख्यमिति वा । २४७ सिद्धं तु पाठात् ॥

१ । ३९ कृन्मेजन्तः ४४९ ॥ २४८ कृन्मेजन्तश्चानिकारोकारप्रकृतिः । २४९ अनन्यप्रकृतिरिति वा । २५० न वा संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति । २५१ प्रयोजनं ह्रस्वत्वं तुग्विधेर्ग्रामणि कुलम् । २५२ नलोपो वृत्रहभिः । २५३ उदुपधमकित्त्वस्य निकुचिते । २५४ नाभावो यञि दीर्घत्वस्यामुना । २५५ आत्त्वं कित्त्वस्योपादास्त । २५६ तिसृचतसृत्वं ङीब्विधेः । २५७ तस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्य । २५८ आत्त्वं पुग्विधेः क्रापयति । २५९ पुग्घ्रस्वत्वस्यादीदपत् । २६० त्यदाद्यकारष्टाब्विधेः । २६१ इड्विधिराकारलोपस्य पपिवान् । २६२ मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य । २६३ नदीह्रस्वत्वं संबुद्धिलोपस्य ॥

१ । ४१ अव्ययीभावश्च ४५१ ॥ २६४ अव्ययीभावस्याव्ययत्वे प्रयोजनं लुङ्मुखस्वरोपचाराः ॥

१ । ४२-४३ शि सर्वनामस्थानम् ३१३ । सुडनपुंसकस्य २२९ ॥ २६५ शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः । २६६ नाप्रतिषेधात् । २६७ अप्राप्तेर्वा ॥

१ । ४४ न वेति विभाषा २५ ॥ २६८ नवेति विभाषायामर्थसंज्ञाकरणम् । २६९ शब्दसंज्ञायां ह्यर्थासंप्रत्ययो यथान्यत्र । २७० इतिकरणोऽर्थनिर्देशार्थः । २७१ समानशब्दप्रतिषेधः । २७२ न वा विधिपूर्वकत्वात्प्रतिषेधसंप्रत्ययो यथा लोके । २७३ विध्यनित्यत्वमनुपपन्नं प्रतिषेधसंज्ञाकरणात् । २७४ सिद्धं तु प्रसज्यप्रतिषेधात् । २७५ विप्रतिषिद्धं तु । २७६ न वा प्रसङ्गसामर्थ्यादन्यत्र प्रतिषेधविषयात् । २७७ विधिप्रतिषेधयोर्युगपद्वचनानुपपत्तिः । २७८ भवतीति चेन्न प्रतिषेधः । २७९ नेति चेन्न विधिः । २८० सिद्धं तु पूर्वस्योत्तरेण बाधितत्वात् । २८१ साध्वनुशासनेऽस्मिन्यस्य विभाषा तस्य साधुत्वम् । २८२ द्वैधाप्रतिपत्तिः । २८३ कार्ययुगपदन्वाचययौगपद्यम् । २८४ आचार्यदेशशीलने च तद्विषयता । २८५ तत्कीर्तने च द्वैधाप्रतिपत्तिः । २८६ अप्राप्ते त्रिसंशयाः (अधिकारोऽयम्) । २८७ द्वन्द्वे च विभाषा जसि । २८८ ऊर्णोतेर्विभाषा । २८९ विभाषोपयमने । २९० अनुपसर्गाद्वा । २९१ विभाषा वृक्षमृगादीनाम् । २९२ उषविदजागृभ्योऽन्यतरस्याम् । २९३ दीपादीनां विभाषा । २९४ विभाषाप्रेप्रथमपूर्वेषु । २९५ तृन्नादीनां विभाषा । २९६ एकहलादौ पूरयितव्येऽन्यतरस्याम् । २९७ श्वादेरिञि पदान्तस्यान्यतरस्याम् । २९८ सपूर्वायाः प्रथमाया विभाषा । २९९ प्रो यञ्चाचि विभाषा । ३०० प्राप्ते च (अयमधिकारोऽतः) । ३०१ विभाषा विप्रलापे । ३०२ विभाषोपपदेन प्रतीयमाने । ३०३ तिरोऽन्तर्धौ, विभाषा कृञि । ३०४ अधिरीश्वरे, विभाषा कृञि । ३०५ दिवस्तदर्थस्य, विभाषोपसर्गे । ३०६ उभयत्र च (अतोऽयमधिकारः) । ३०७ हक्रोरन्यतरस्याम् । ३०८ न यदि, विभाषा साकाङ्क्षे । ३०९ विभाषा श्वेः । ३१० विभाषा संघुषास्वनाम् ॥

१ । ४५ इग्यणः संप्रसारणम् ३५८ ॥ ३११ संप्रसारणसंज्ञायां वाक्यसंज्ञा चेद्वर्णविधिः । ३१२ वर्णसंज्ञा चेन्निर्वृत्तिः । ३१३ विभक्तिविशेषनिर्देशस्तु ज्ञापक उभयसंज्ञात्वस्य ॥

१ । ४६ आद्यन्तौ टकितौ ३६ ॥ ३१४ टकितोराद्यन्तविधाने प्रत्ययप्रतिषेधः । ३१५

परवचनात्सिद्धम् । ३१६ परवचनात्सिद्धमिति चेन्नापवादत्वात् । ३१७ सिद्धं तु षष्ठ्यधिकारे वचनात् । ३१८ आद्यन्तयोर्वा षष्ठ्यर्थत्वात्तदभावे संप्रत्ययः ॥

१ । ४७ मिदचोऽन्त्यात्परः ३७ ॥ ३१९ मिदचोऽन्त्यात्पर इति स्थानपरप्रत्ययापवादः । ३२० अन्त्यात्पूर्वो मस्जेरनुषङ्गसंयोगादिलोपार्थम् । ३२१ भर्जिमच्योश्च । ३२२ अभक्ते दीर्घनलोपस्वरणत्वानुस्वारशीभावाः । ३२३ परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वारशीभावे नकारप्रतिषेधः । ३२४ पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च । ३२५ न वा बहिरङ्गलक्षणत्वात् ॥

१ । ४८ एच इग्घ्रस्वादेशे ३८ ॥ ३२६ एच इक् सवर्णाकारनिवृत्त्यर्थम् । ३२७ दीर्घप्रसङ्गः । ३२८ दीर्घप्रसङ्गस्तु निवर्तकत्वात् । ३२९ सिद्धमेङः सस्थानत्वात् । ३३० ऐचोश्चोत्तरभूयस्त्वात् ॥

१ । ४९ षष्ठी स्थानेयोगा ३८ ॥ ३३१ षष्ठ्याः स्थानेयोगवचनं नियमार्थम् । ३३२ अवयवषष्ठ्यादिष्वतिप्रसङ्गः शासो गोह इति । ३३३ अवयवषष्ठ्यादीनां चाप्राप्तियोगस्यासंदिग्धत्वात् । ३३४ विशिष्टा वा षष्ठी स्थानेयोगा ॥

१ । ५० स्थानेऽन्तरतमः ३९ ॥ ३३५ स्थानिन एकत्वनिर्देशादनेकादेशनिर्देशाच्च सर्वप्रसङ्गः, तस्मात्स्थानेऽन्तरतमवचनम् । ३३६ स्थानेऽन्तरतमनिर्वर्तके स्थानिनिर्वृत्तिः । ३३७ निर्वृत्तप्रतिपत्तौ निर्वृत्तिः । ३३८ अनर्थकं च । ३३९ प्रत्यात्मवचनं च । ३४० प्रत्यात्मवचनमशिष्यं स्वभावसिद्धत्वात् । ३४१ अन्तरतमवचनं च । ३४२ व्यञ्जनस्वरव्यतिक्रमे च तत्कालप्रसङ्गः । ३४३ अक्षु चानेकवर्णादेशेषु । ३४४ गुणवृद्ध्येज्भावेषु च । ३४५ ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गोऽविशेषात् । ३४६ न वा ऋवर्णस्य स्थाने रपरप्रसङ्गादवर्णस्यान्तर्यम् । ३४७ सर्वादेशप्रसङ्गस्त्वनेकाल्त्वात् । ३४८ न वानेकाल्त्वस्य तदाश्रयत्वादृवर्णादेशस्याविघातः । ३४९ संप्रयोगो वा नष्टाश्वदग्धरथवत् । ३५० एजवर्णयोगदेशेऽवर्णं स्थानिनोऽवर्णप्रधानत्वात् । ३५१ सिद्धं तूभयान्तर्यात् ॥

१ । ५१ उरण्रपरः ७० ॥ ३५२ उरण्रपरवचनमन्यनिवृत्त्यर्थं चेदुदात्तादिषु दोषः । ३५३ य उः स्थाने स रपर इति चेद्गुणवृद्ध्योरवर्णाप्रतिपत्तिः । ३५४ सिद्धं तु प्रसङ्गे रपरत्वात् । ३५५ आदेशो रपर इति चेद्रीरिविधिषु रपरप्रतिषेधः । ३५६ उदात्तादिषु च । ३५७ एकादेशस्योपसंख्यानम् । ३५८ अवयवग्रहणात्सिद्धम् । ३५९ अवयवग्रहणात्सिद्धमिति चेदादेशे रान्तप्रतिषेधः । ३६० अभक्ते दीर्घलत्वयगभ्यस्तस्वरहलादिशेषविसर्जनीयप्रतिषेधः प्रत्ययाव्यवस्था च । ३६१ पूर्वान्ते वैवधारणं विसर्जनीयप्रतिषेधो यक्स्वरश्च । ३६२ परादावकारलोपेत्त्वपुक्प्रतिषेधश्चङ्युपधाह्रस्वत्वमिटोऽव्यवस्थाभ्यासलोपोऽभ्यस्तादिस्वरो दीर्घत्वं च ॥

१ । ५२ अलोऽन्त्यस्य ४२ ॥ ३६३ अलोऽन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः । ३६४ इतरथा ह्यनिष्टप्रसङ्गः । ३६५ योगशेषे च ॥

१ । ५३ ङिच्च ४३ ॥ ३६६ तातङि ङित्करणस्य सावकाशत्वाद्विप्रतिषेधात्सर्वादेशः ॥

१ । ५४ आदेः परस्य ४४ ॥ ३६७ अलोऽन्त्यस्यादेः परस्यानेकाल्शित्सर्वस्येत्यपवादविप्रतिषेधात्सर्वादेशः ॥

१ । ५६ स्थानिवदादेशोऽनल्विधौ ४९ ॥ ३६८ स्थान्यादेशपृथक्त्वादादेशे स्थानि-

वदनुदेशो गुरुवद्गुरुपुत्र इति यथा । ३६९ अल्विधौ प्रतिषेधेऽविशेषणेऽप्रातिस्त्र-स्यादर्शनात् । ३७० सामान्यातिदेशे विशेषानतिदेशः । ३७१ सत्याश्रये विधिरिष्टः । ३७२ प्रतिषेधस्तु प्राप्नोत्यल्विधित्वात् । ३७३ न वानुदेशिकस्य प्रतिषेधादितरेण भावः । ३७४ आदेश्याल्विधिप्रतिषेधे कुरुवधपिबां गुणवृद्धिप्रतिषेधः । ३७५ आदेश्यादेश इति चेत्सुनिर्दुद-तिदिष्टेषूपसंख्यानम् । ३७६ एकदेशविकृतस्योपसंख्यानम् । ३७७ एकदेशविकृतस्यानन्य-त्वात्सिद्धम् । ३७८ अनित्यविज्ञानं तु तस्मादुपसंख्यानम् । ३७९ एकदेशविकृतेषूपसंख्यानम् । ३८० अनादेशत्वात् । ३८१ रूपान्यत्वाच्च । ३८२ आदेशः स्थानिवदिति चेन्नानाश्रितत्वात् ॥ ३८३ आश्रय इति चेदल्विधिप्रसङ्गः । इति भारद्वाजीयपाठः) । ३८४ अनुपपन्नं स्थान्या-देशत्वं नित्यत्वात् । ३८५ सिद्धं तु यथा लौकिकवैदिकेष्वभूतपूर्वेऽपि स्थानशब्दप्रयोगात् । ३८६ कार्यविपरिणामाद्वा सिद्धम् । ३८७ अपवादप्रसङ्गस्तु स्थानिवत्त्वात् । ३८८ सिद्धं तु षष्ठीनिर्दिष्टस्य स्थानिवद्वचनात् । ३८९ तस्य दोषस्तयादेश उभये प्रतिषेधः । ३९० जात्या-ख्यायां वचनातिदेशे स्थानिवद्भावप्रतिषेधः । ३९१ ङ्याब्ग्रहणेऽदीर्घः । ३९२ आहिभुवो-रीट्प्रतिषेधः । ३९३ वध्यादेशे वृद्धितत्त्वप्रतिषेधः । ३९४ इड्विधिश्च । ३९५ आकारान्तान्नु-क्षुकप्रतिषेधः । ३९६ लोडादेशे शाभावजभावधित्वहिलोपैत्वप्रतिषेधः । ३९७ त्रयादेशे स्रन्त-प्रतिषेधः । ३९८ आम्विधौ च । ३९९ स्वरे वस्वादेशे । ४०० गोः पूर्वणित्त्वात्त्वस्वरेषु । ४०१ करोतिपिब्योः प्रतिषेधः ॥

१ । ५७ अचः परस्मिन्पूर्वविधौ ५० ॥ ४०२ अपरविधाविति वक्तव्यम् । ४०३ अचः पूर्वत्वविज्ञानादेचोः सिद्धम् । ४०४ तन्नादेशलक्षणप्रतिषेधः । ४०५ असिद्धव-चनात्सिद्धम् । ४०६ असिद्धवचनात्सिद्धमिति चेदुत्सर्गलक्षणानामनुदेशः । ४०७ असिद्धव-चनात्सिद्धमिति चेन्नान्यस्यासिद्धवचनादन्यस्य भावः । ४०८ तस्मात्स्थानिवद्वचनमसिद्धत्वं च । ४०९ काममतिदिश्यतां वा सच्चासच्चापि नेह भारोऽस्ति । कल्प्यो हि वाक्यशेषो वाक्यं वक्त-र्यधीनं हि ॥ ४१० अनन्तरस्य चेदेकानुदात्तद्विगुस्वरगतिनिघातेषूपसंख्यानम् । ४११ पूर्वमात्रस्येति चेदुपधाह्रस्वत्वम् । ४१२ गुरुसंज्ञा च । ४१३ न वा संयोगस्यापूर्वविधित्वात् । ४१४ एकादेशस्योपसंख्यानम् । ४१५ उभयनिमित्तत्वात् । ४१६ उभयादेशत्वाच्च । ४१७ हलचोरादेशः स्थानिवदिति चेद्विंशतेस्तिलोप एकादेशः । ४१८ केकयमित्रय्वोरियादेश इत्त्वम् । ४१९ उत्तरपदलोपे च । ४२० यङ्लोपे यणियङुवङः । ४२१ अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः । ४२२ अविशेषेण स्थानिवदिति चेल्लोपयणादेशे गुरुविधिः । ४२३ द्विर्वचनादयश्च प्रतिषेधे । ४२४ क्सलोपे लुग्वचनम् । ४२५ हन्तेर्घत्वम् । ४२६ ग्रहणेषु स्थानिवदिति चेज्जग्ध्यादिष्वादेशप्रतिषेधः । ४२७ यणादेशे युलोपेत्त्वानुनासिकात्त्वप्रतिषेधः । ४२८ रायात्वप्रतिषेधश्च । ४२९ दीर्घे यलोपप्रतिषेधः । ४३० अतो दीर्घे यलोपवचनम् ॥

१ । ५८ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ५१ ॥ ४३१ प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत् । ४३२ क्विलुगुपधात्वचङ्पर-निर्ह्रासकुत्वेषूपसंख्यानम् । ४३३ पूर्वत्रासिद्धे च । ४३४ प्रयोजनं क्सलोपः सलोपे । ४३५ दध आकारलोप आदिचतुर्थत्वे । ४३६ हलो यमां यमि लोपे । ४३७ अल्लोपणिलोपौ संयो-

गान्तलोपप्रभृतिषु । ४३८ द्विर्वचनादीनि च । ४३९ वरेयलोपस्वरवर्जम् । ४४० तस्य दोषः संयोगादिलोपलत्वणत्वेषु ॥

१ । ५९ द्विर्वचनेऽचि २२४३ ॥ ४४१ आदेशे स्थानिवदनुदेशात्तद्वतो द्विर्वचनम् । ४४२ तत्राभ्यासरूपम् । ४४३ अज्ग्रहणं तु ज्ञापकं रूपस्थानिवद्भावस्य । ४४४ तत्र गाङ्प्रतिषेधः । ४४५ कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपम् । ४४६ प्रत्यय इति चेत्कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपम् । ४४७ द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानिवद्वचनम् । ४४८ ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य ॥

१ । ६० अदर्शनं लोपः ९३ ॥ ४४९ सर्वप्रसङ्गस्तु सर्वस्यानवादृष्टत्वात् । ४५० तत्र प्रत्ययलक्षणप्रतिषेधः । ४५१ सिद्धं तु प्रसक्तादर्शनस्य लोपसंज्ञित्वात् ॥

१ । ६१ प्रत्ययस्य लुक्श्लुलुपः २६० ॥ ४५२ लुमति प्रत्ययग्रहणमप्रत्ययसंज्ञाप्रतिषेधार्थम् । ४५३ प्रयोजनं तद्धितलुकि कंसीयपरशव्ययोर्लुकि च गोप्रकृतिनिवृत्त्यर्थम् । ४५४ योगविभागात्सिद्धम् । ४५५ कंसीयपरशव्ययोर्विशिष्टनिर्देशात्सिद्धम् । ४५६ षष्ठीनिर्देशार्थं तु । ४५७ अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः । ४५८ सर्वादेशार्थं वा वचनप्रामाण्यात् । ४५९ उत्तरार्थं तु ॥

१ । ६२ प्रत्ययलोपे प्रत्ययलक्षणम् २६२ ॥ ४६० प्रत्ययलोपे प्रत्ययलक्षणवचनं सद्न्वाख्यानाच्छास्त्रस्य । ४६१ लुक्युपसंख्यानम् । ४६२ लोपे हि विधानम् । ४६३ न वादर्शनस्य लोपसंज्ञित्वात् । ४६४ प्रत्ययादर्शनं तु लुमत्संज्ञम् । ४६५ तत्र लुकि श्लुविधिप्रतिषेधः । ४६६ न वा पृथक्संज्ञाकरणात् । ४६७ लुमति प्रतिषेधाद्वा । ४६८ सतो निमित्ताभावात्पदसंज्ञाभावः । ४६९ तुग्दीर्घत्वयोश्च विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात्परिवीरिति । ४७० सिद्धं तु स्थानिसंज्ञानुदेशादान्यभाव्यस्य । ४७१ भसंज्ञाङीप्ष्फगोरात्त्वेषु च सिद्धम् । ४७२ तस्य दोषो ङीनकारलोपेत्त्वेम्विधयः । ४७३ प्रयोजनमवृक्काशिलोपे नुममामौ गुणवृद्धिदीर्घत्वेमडाड्भम्विधयः । ४७४ भसंज्ञाङीप्ष्फगोरात्वेषु च दोषः ॥

१ । ६३ न लुमताङ्गस्य २६३ ॥ ४७५ लुमति प्रतिषेध एकपदस्वरस्योपसंख्यानम् । ४७६ सर्वामन्त्रितसिज्लुक्स्वरवर्जम् । ४७७ प्रयोजनं श्निन्त्किलुकि स्वराः । ४७८ पथिमथोः सर्वनामस्थाने । ४७९ अह्नो रविधौ । ४८० उत्तरपदत्वे चापदादिविधौ । ४८१ द्वन्द्वेऽन्त्यस्य । ४८२ सिच उसो प्रसङ्ग आकारप्रकरणात् । ४८३ युष्मदस्मदोः स्थग्रहणात् । ४८४ आमि लिलोपात्तस्य चानिघातस्तस्माच्च निघातः । ४८५ अङ्गाधिकार इटो विधिप्रतिषेधौ । ४८६ क्रमेर्दीर्घत्वं च । ४८७ न लुमता तस्मिन्निति चेद्धानिणिङादेशास्तलोपे ॥

१ । ६५ अलोऽन्त्यात्पूर्व उपधा २५९ ॥ ४८८ उपधासंज्ञायामल्ग्रहणमन्त्यनिर्देशश्चेत्संघातप्रतिषेधः । ४८९ अन्त्यविज्ञानात्सिद्धम् । ४९० अन्त्यविज्ञानात्सिद्धमिति चेन्नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे । ४९१ प्रयोजनमव्यक्तानुकरणस्यात इतौ । ४९२ घ्वसोरेद्धावभ्यासलोपश्च । ४९३ आपि लोपोऽकोऽनचि । ४९४ अत्र लोपोऽभ्यासस्य । ४९५ अलोऽन्त्यात्पर्वो लुपधेति वा । ४९६ अवचनाल्लोकविज्ञानात्सिद्धम् ॥

१ । ६६-६७ तस्मिन्निति निर्दिष्टे पूर्वस्य ४० । तस्मादित्युत्तरस्य ४१ ॥ ४९७ निर्दिष्टग्रहणमानन्तर्यार्थम् । ४९८ तस्मिंस्तस्मादिति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थं

वचनं दध्युदकं पचत्योदनम् । ४९९ उभयनिर्देशे विप्रतिषेधात्पञ्चमीनिर्देशः । ५०० प्रयोजनमतो लसार्वधातुकानुदात्तत्वे । ५०१ बहोरिष्ठादीनामादिलोपे । ५०२ गोतो णित् । ५०३ रुदादिभ्यः सार्वधातुके । ५०४ आने मुगीदासः । ५०५ आमि सर्वनाम्नः सुट् । ५०६ घेर्ङित्याण्नद्याः । ५०७ याडापः । ५०८ ङमो ह्रस्वादचि ङमुण्नित्यम् । ५०९ विभक्तिविशेषनिर्देशानवकाशत्वादविप्रतिषेधः । ५१० यथार्थं वा षष्ठीनिर्देशः । ५११ प्रकल्पकमिति चेन्नियमाभावः । ५१२ प्रकृतिविकाराव्यवस्था च । ५१३ सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रकृतिस्तत्रोभयकार्यप्रसङ्गः ॥

१ । ६८ स्वं रूपं शब्दस्याशब्दसंज्ञा २९ ॥ ५१४ शब्देनार्थगतेरर्थस्यासंभवात्तद्वाचिनः संज्ञाप्रतिषेधार्थं स्वं रूपवचनम् । ५१५ न वा शब्दपूर्वको ह्यर्थे संप्रत्ययस्तस्मादर्थनिवृत्तिः । ५१६ संज्ञाप्रतिषेधानर्थक्यं वचनप्रामाण्यात् । ५१७ मन्त्राद्यर्थमिति चेच्छास्त्रसामर्थ्यादर्थगतेः सिद्धम् । ५१८ सित्तद्विशेषाणां वृक्षाद्यर्थम् । ५१९ पित्पर्यायवचनस्य च स्वाद्यर्थम् । ५२० जित्पर्यायवचनस्यैव राजाद्यर्थम् । ५२१ झित्तस्य च तद्विशेषाणां च मत्स्याद्यर्थम् ॥

१ । ६९ अणुदित्सवर्णस्य चाप्रत्ययः १४ ॥ ५२२ अण्सवर्णस्येति स्वरानुनासिक्यकालभेदात् । ५२३ तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात् । ५२४ ह्रस्वसंप्रत्ययादिति चेदुच्चार्यमाणसंप्रत्यायकत्वाच्छब्दस्यावचनम् । ५२५ वर्णपाठ उपदेश इति चेदवरकालत्वात्परिभाषाया अनुपदेशः । ५२६ तत्रानुवृत्तिनिर्देशे सवर्णाग्रहणमनण्त्वात् । ५२७ सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणात् । ५२८ अनन्यत्वाच्च । ५२९ अनेकान्तो ह्यनन्यत्वकरः । ५३० तद्वच्च हल्ग्रहणेषु । ५३१ द्रुतविलम्बितयोश्चानुपदेशात् । ५३२ वृत्तिपृथक्त्वं तु नोपलभ्यते । ५३३ तस्मात्तत्र तपरनिर्देशात्सिद्धम् ॥

१ । ७० तपरस्तत्कालस्य १९ ॥ ५३४ तपरस्तत्कालस्येति नियमार्थमिति चेद्दीर्घग्रहणे स्वरभिन्नाग्रहणम् । ५३५ प्राप्तकमिति चेद्ध्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः । ५३६ विप्रतिषेधात्सिद्धम् । ५३७ द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात् । ५३८ सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद्वृत्तयो विशेष्यन्ते । ५३९ भेर्याघातवत् ॥

१ । ७१ आदिरन्त्येन सहेता २ ॥ ५४० आदिरन्त्येन सहेतेत्यसंप्रत्ययः संज्ञिनोऽनिर्देशात् । ५४१ सिद्धं त्वादिरिता सह तन्मध्यस्येति वचनात् । ५४२ संबन्धिशब्दैर्वा तुल्यम् ॥

१ । ७२ येन विधिस्तदन्तस्य २६ ॥ ५४३ येन विधिस्तदन्तस्येति चेद्ग्रहणोपाधीनां तदन्तोपाधिप्रसङ्गः । ५४४ सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात् । ५४५ समासप्रत्ययविधौ प्रतिषेधः । ५४६ उगिद्वर्णग्रहणवर्जम् । ५४७ अकच्भम्वतः सर्वनामाव्ययधातुविधावुपसंख्यानम् । ५४८ सिद्धं तु तदन्तान्तवचनात् । ५४९ तदेकदेशविज्ञानाद्वा सिद्धम् । ५५० प्रयोजनं सर्वनामाव्ययसंज्ञायाम् । ५५१ उपपदविधौ भयाढ्यादिग्रहणम् । ५५२ ङीब्विधावुगिद्ग्रहणम् । ५५३ प्रतिषेधे स्वस्रादिग्रहणम् । ५५४ अपरिमाणबिस्तादिग्रहणं च प्रतिषेधे । ५५५ दिति । ५५६ रोण्या अण् । ५५७ तस्य च । ५५८ रथसीताहलेभ्यो यद्विधौ । ५५९ सुसर्वार्धदिक्शब्देभ्यो जनपदस्य । ५६० क्रतोर्वृद्धिमद्विधाववयवानाम् । ५६१ ठञ्विधौ संख्यायाः । ५६२ धर्मान्नञः । ५६३ पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च । ५६४ प्रयोजनमिष्टकेषीकामालानां चिततूलभारिषु । ५६५ महदप्स्वसृनप्तॄणां दीर्घविधौ । ५६६ पद्युष्मदस्मदस्थ्याद्यनडुहो नुम् । ५६७ सुप-

थिमथिपुंगोसखिचतुरनडुत्त्रिग्रहणम् । ५६८ त्यदादिविधिभस्त्रादिस्त्रीग्रहणं च । ५६९ वर्णग्रहणं च सर्वत्र । ५७० प्रत्ययग्रहणं चापञ्चम्याः । ५७१ यस्मिन्विधिस्तदादावल्ग्रहणे ॥

१ । ७३ वृद्धिर्यस्याचामादिस्तद्वृद्धम् १३३९ ॥ ५७२ वृद्धसंज्ञायामजसंनिवेशादनादित्वम् । ५७३ एकान्तादित्वे च सर्वप्रसङ्गः । ५७४ सिद्धमजाकृतिनिर्देशात् । ५७५ व्यञ्जनस्याविद्यमानत्वं यथान्यत्र । ५७६ वा नामधेयस्य । ५७७ गोत्रोत्तरपदस्य च । ५७८ गोत्रान्ताद्वासमस्तवत् । ५७९ जिह्वाकात्यहरितकात्यवर्जम् ॥

२ । १ गाङ्कुटादिभ्योऽञ्णिन्ङित् २४६१ ॥ ५८० ङित्किद्वचने तयोरभावादप्रसिद्धिः । ५८१ भवतीति चेदादेशप्रतिषेधः । ५८२ संज्ञाकरणे क्विद्ग्रहणेऽसंप्रत्ययः शब्दभेदात् । ५८३ तद्वदतिदेशेऽकिद्विधिप्रसङ्गः । ५८४ सिद्धं तु प्रसज्य प्रतिषेधात् । ५८५ सर्वत्र सनन्तादात्मनेपदप्रतिषेधः । ५८६ सिद्धं तु पूर्वस्य कार्यातिदेशात् । ५८७ पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसंप्रसारणं सार्वधातुकचङादिषु । ५८८ जाग्रोऽगुणविधिः । ५८९ कुटादीनामिट्प्रतिषेधः । ५९० क्त्वायां कित्प्रतिषेधश्च ॥

२ । ४ सार्वधातुकमपित् २२३४ ॥ ५९१ अपिन्ङिदिति चेच्छ्वेकादेशप्रतिषेध आदिवत्त्वात् । ५९२ न पिन्ङिदिति चेदुत्तमैकादेशप्रतिषेधः ॥

२ । ५ असंयोगाल्लिट् कित् २२४२ ॥ ५९३ ऋदुपधेभ्यो लिटः कित्त्वं गुणात्प्रतिषेधेन ।

२ । ६ इन्धिभवतिभ्यां च ३३९३ ॥ ५९४ इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां किद्वचनानर्थक्यम् ॥

२ । ९ इको झल् २६१२ ॥ ५९५ इकः कित्त्वं गुणो मा भूत् । ५९६ दीर्घारम्भात् । ५९७ कृते भवेत् । ५९८ अनर्थकं तु । ५९९ ह्रस्वार्थम् । ६०० दीर्घाणां तु प्रसज्यते । ६०१ सामर्थ्याद्धि पुनर्भाव्यम् । ६०२ ऋदित्त्वं दीर्घसंश्रयम् । ६०३ दीर्घाणां नाकृते दीर्घे । ६०४ णिलोपस्तु प्रयोजनम् ॥

२ । १० हलन्ताच्च २६१३ ॥ ६०५ दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् ॥

२ । १७ स्थाघ्वोरिच्च २३८९ ॥ ६०६ इच्च कस्य तकारेत्त्वम् । ६०७ दीर्घो मा भूत् । ६०८ कृतेऽपि सः । ६०९ अनन्तरे प्लुतो मा भूत् । ६१० प्लुतश्च विषये स्मृतः ॥

२ । १८ न क्त्वा सेट् ३३२२ ॥ ६११ न सेडिति कृते कित्त्वे । ६१२ निष्ठायामवधारणात् । ६१३ ज्ञापकान्न परोक्षायाम् । ६१४ सनि झल्ग्रहणं विदुः । ६१५ इत्त्वं कित्संनियोगेन । ६१६ रेण तुल्यं सुधीवनि । ६१७ वस्वर्थम् । ६१८ किदतीदेशात् । ६१९ निगृहीतिः । ६२० क्त्वा च विग्रहात् ॥

२ । २१ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ३०५६ ॥ ६२१ उदुपधाच्छपः ॥

२ । २२ पूङः क्त्वा च ३०५१ ॥ ६२२ पूङः क्त्वानिष्ठयोरिटि वा प्रसङ्गः सेट्प्रकरणात् । ६२३ न वा सेट्त्वस्याकिदाश्रयत्वादनिटि वा कित्त्वम् । ६२४ इड्विधौ ह्यग्रहणम् । ६२५ ('नित्यमकित्त्वमिडाद्योः क्त्वाग्रहणमुत्तरार्थम्' इति भारद्वाजीयपाठः) ॥

२ । २६ रलो व्युपधाद्धलादेः संश्च २६१७ ॥ ६२६ रलः क्त्वासनोः कित्त्वम् ॥

२ । २७ ऊकालोऽज्झ्रस्वदीर्घप्लुतः ४ ॥ ६२७ ह्रस्वादिषु समसंख्याप्रसिद्धिर्निर्देशवैषम्यात् ।

६२८ सिद्धं तु समसंख्यत्वात्। ६२९ त्रयाणां हि विकारनिर्देशः। ६३० दीर्घप्लुतयोस्तु पूर्वसंज्ञाप्रसङ्गः। ६३१ सिद्धं तु तपरनिर्देशात्॥

२। २८ अचश्च ३९॥ ६३२ ह्रस्वादिविधिरलोऽन्त्यस्येति चेद्यचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेष्वज्ग्रहणम्। ६३३ अचश्चेन्नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेष्वनन्त्यप्रतिषेधः। ६३४ संज्ञया विधाने नियमः। ६३५ अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्॥

२। २९-३० उच्चैरुदात्तः ५। नीचैरनुदात्तः ६॥ ६३६ उच्चनीचस्यानवस्थितत्वात्संज्ञाप्रसिद्धिः। ६३७ सिद्धं तु समानप्रक्रमवचनात्॥

२। ३१ समाहारः स्वरितः ७॥ ६३८ समाहारोऽचोश्चेन्नाभावात्। ६३९ गुणयोश्चेन्नाच्प्रकरणात्। ६४० सिद्धं त्वच्समुदायस्याभावात्तद्गुणे संप्रत्ययः॥

२। ३२ तस्यादित उदात्तमर्धह्रस्वम् ८॥ ६४१ स्वरितस्यार्धह्रस्वोदात्तादोदात्तस्वरितपरस्य सन्नतरादूर्ध्वमुदात्तादनुदात्तस्य स्वरिताकार्यं स्वरितादिति सिद्ध्यर्थम्। ६४२ स्वरितोदात्तार्थं च। ६४३ स्वरितोदात्ताच्चास्वरितार्थम्। ६४४ स्वरितपरसन्नतरार्थं च। ६४५ देवब्रह्मणोरनुदात्तवचनं ज्ञापकं स्वरितादिति सिद्धत्वस्य॥

२। ३७ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ३६६६॥ ६४६ सुब्रह्मण्यायामोकार उदात्तः। ६४७ आकार आख्याते परादिश्च। ६४८ वाक्यादौ च द्वे द्वे। ६४९ मघवन्वर्जम्। ६५० सुत्यापराणामन्तः। ६५१ असावित्यन्तः। ६५२ अमुष्येत्यन्तः। ६५३ स्यान्तस्योपोत्तमं च। ६५४ वा नामधेयस्य॥

२। ३८ देवब्रह्मणोरनुदात्तः ३६६७॥ ६५५ देवब्रह्मणोरनुदात्तत्वमेके॥

२। ३९ स्वरितात्संहितायामनुदात्तानाम् ३६६८॥ ६५६ स्वरितात्संहितायामनुदात्तानामिति चेद्व्यचेकयोरैकश्रुत्यवचनम्। ६५७ अविशेषेणैकश्रुत्यमिति चेद्व्यवहितानामप्रसिद्धिः। ६५८ अनेकमपीति तु वचनात्सिद्धम्॥

२। ४१ अपृक्त एकाल्प्रत्ययः ३७१॥ ६५९ अपृक्तसंज्ञायां हल्ग्रहणं स्वादिलोपे हलोऽग्रहणार्थम्। ६६० अणिञोर्लुगर्थमल्ग्रहणम्। ६६१ अणिञोर्लुगर्थमिति चेण्णेऽतिप्रसङ्गः। ६६२ वचनप्रामाण्यादिति चेत्फाग्निवृत्त्यर्थं वचनम्। ६६३ तैलादिषु वचनात्सिद्धम्॥

२। ४२ तत्पुरुषः समानाधिकरणः कर्मधारयः ७४९॥ ६६४ तत्पुरुषः समानाधिकरणः कर्मधारय इति चेत्समासस्यैकार्थत्वादप्रसिद्धिः। ६६५ सिद्धं तु पदसामानाधिकरण्यात्॥

२। ४३ प्रथमानिर्दिष्टं समास उपसर्जनम् ६९३॥ ६६६ प्रथमानिर्दिष्टं समास उपसर्जनमिति चेदनिर्देशात्प्रथमायाः समासे संज्ञाप्रसिद्धिः। ६६७ सिद्धं तु समासविधाने वचनात्। ६६८ न वा तादर्थ्यात्ताच्छब्द्यम्। ६६९ यस्य विधौ प्रथमानिर्देशस्ततोऽन्यत्राप्युपसर्जनसंज्ञाप्रसङ्गः। ६७० सिद्धं तु यस्य विधौ तं प्रतीति वचनात्॥

२। ४४ एकविभक्ति चापूर्वनिपाते ६९९॥ ६७१ नाप्रतिषेधात्। ६७२ अप्राप्तेर्वा। ६७३ एकविभक्तावषष्ठ्यन्तवचनम्। ६७४ प्रयोजनं द्विगुप्राप्तालंपूर्वोपसर्गाः क्तार्थे॥

२। ४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् १७८॥ ६७५ अर्थवत्यनेकपदप्रसङ्गः। ६७६ समुदायोऽनर्थक इति चेदवयवार्थवत्त्वात्समुदायार्थवत्त्वं यथा लोके। ६७७ वाक्य-

प्रतिषेधोऽर्थवत्त्वात्। ६७८ पदार्थादन्यस्यानुपलब्धिरिति चेत्पदार्थाभिसंबन्धस्योपलब्धेः ६७९ तस्मात्प्रतिषेधः। ६८० अर्थवत्समुदायानां समासग्रहणं नियमार्थम्। ६८१ अर्थवत्ता नोपपद्यते केवलेनावचनात्। ६८२ न वा प्रत्ययेन नित्यसंबन्धात्केवलस्याप्रयोगः। ६८३ सिद्धं त्वन्वयव्यतिरेकाभ्याम्। ६८४ संघातार्थवत्त्वाच्चेति चेद्दृष्टो ह्यतदर्थेन गुणेन गुणिनोऽर्थभावः। ६८५ निपातस्यानर्थकस्य प्रातिपदिकत्वम्। ६८६ अप्रत्यय इति चेत्तिवेकादेशे प्रतिषेधोऽन्तवत्त्वात्। ६८७ न प्रत्यय इति चेदूङेकादेशे प्रतिषेध आदिवत्त्वात्। ६८८ सुब्लोपे च प्रत्ययलक्षणत्वात्॥

२।४७ ह्रस्वो नपुंसके प्रातिपदिकस्य ३१८॥ ६८९ नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं तिङ्निवृत्त्यर्थम्। ६९० अव्ययप्रतिषेधः। ६९१ न वा लिङ्गाभावात्। ६९२ यणेकादेशदीर्घत्वेषु प्रतिषेधः। ६९३ यणेकादेशदीर्घत्वेषु बहिरङ्गलक्षणत्वात्सिद्धम्॥

२।४८ गोस्त्रियोरुपसर्जनस्य ६५६॥ ६९४ उपसर्जनह्रस्वत्वे च। ६९५ गोटाङ्ग्रहणं कृन्निवृत्त्यर्थम्। ६९६ ईयसो बहुव्रीहौ पुंवद्वचनम्। ६९७ पूर्वपदस्य च प्रतिषेधो गोसमासनिवृत्त्यर्थम्। ६९८ कपि च। ६९९ द्वन्द्वे च॥

२।४९ लुक्तद्धितलुकि १४०८॥ ७०० तद्धितलुक्यवन्त्यादीनां प्रतिषेधः। ७०१ तद्धितलुक्यवन्त्यादीनामप्रतिषेधोऽलुक्परत्वात्॥

२।५० इद्गोण्याः १७०३॥ ७०२ इद्गोण्या नेति वक्तव्यम्। ७०३ ह्रस्वता हि विधीयते। ७०४ इति वा वचने तावत्। ७०५ मात्रार्थं वा कृतं भवेत्। ७०६ गोण्या इत्त्वं प्रकरणात्। ७०७ सूच्याद्यर्थमथापि वा॥

२।५१ लुपि युक्तवद्व्यक्तिवचने १२९४॥ ७०८ अन्यत्राभिधेयव्यक्तिवचनभावाल्लुपि युक्तवदनुदेशः। ७०९ लुपोऽदर्शनसंज्ञित्वादर्थगतिर्नोपपद्यते। ७१० न वादर्शनस्याशक्यत्वादर्थगतिः साहचर्यात्। ७११ योगाभावाच्चान्यस्य। ७१२ समास उत्तरपदस्य बहुवचनस्य लुपः॥

२।५२ विशेषणानां चाजातेः १३००॥ ७१३ विशेषणानां वचनं जातिनिवृत्त्यर्थम्। ७१४ समानाधिकरणत्वात्सिद्धम्। ७१५ हरीतक्यादिषु व्यक्तिः। ७१६ खलतिकादिषु वचनम्। ७१७ मनुष्यलुपि प्रतिषेधः॥

२।५८ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ८१७॥ ७१८ जात्याख्यायां सामान्याभिधानादैकार्थ्यम्। ७१९ अर्थातिदेशात्सिद्धम्। ७२० संख्याप्रयोगे प्रतिषेधः। ७२१ अस्मदो नामयुवप्रत्यययोश्च ('अस्मदः सविशेषणस्य प्रयोगे नेत्येव' इत्यपर आह)। ७२२ अशिष्यं वा बहुवत्पृथक्त्वाभिधानात्। ७२३ जातिशब्देन हि द्रव्याभिधानम्॥

२।६१–६२ छन्दसि पुनर्वस्वोरेकवचनम् ३३८७। विशाखयोश्च ३३८८॥ ७२४ पुनर्वसुविशाखयोः सुपां सुलुक्पूर्वसवर्णेति सिद्धम्॥

२।६४ सरूपाणामेकशेष एकविभक्तौ १८८॥ ७२५ प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याभिधानम्। ७२६ तत्रानेकार्थाभिधानेऽनेकशब्दत्वम्। ७२७ तस्मादेकशेषः। ७२८ एकविभक्ताविति चेन्नाभावाद्विभक्तेः। ७२९ पृथक्सर्वेषामिति चेदेकशेषे पृथग्विभक्त्युपलब्धिस्तदाश्रयत्वात्। ७३० समास इति चेत्स्वरसमासान्तेषु दोषः। ७३१ अङ्गाश्रये चैकशेषवचनम्। ७३२ तिङ्समासे तिङ्समासवचनम्। ७३३ तिङ्विधिप्रतिषेधश्च। ७३४ असमासे वच-

नलोपः । ७३५ द्विवचनबहुवचनविधिः । ७३६ द्वन्द्वप्रतिषेधश्च । ७३७ विभक्त्यन्तानामेक-
शेष एकविभक्त्यन्तानामिति तु पृथग्विभक्तिप्रतिषेधार्थम् । ७३८ न वार्थविप्रतिषेधाद्युगपद्व-
चनाभावः । ७३९ अनेकार्थाश्रयश्च पुनरेकशेषः । ७४० तस्मान्नैकशब्दत्वम् । ७४१ प्रातिप-
दिकानामेकशेषे मातृमात्रोः प्रतिषेधः सरूपत्वात् । ७४२ हरितहरिणश्येतश्येनरोहितरोहि-
णानां स्त्रियामुपसंख्यानम् । ७४३ न वा पदस्यार्थे प्रयोगात् । ७४४ सर्वत्रापत्यादिपूपसंख्या-
नम् । ७४५ सिद्धं तु समानार्थानामेकशेषवचनात् । ७४६ नानार्थानामपि सरूपाणाम् ।
७४७ एकार्थानामपि विरूपाणाम् । ७४८ स्वराभिन्नानां यस्योदात्तस्वरविधिः । ७४९ संख्याया
अर्थासंप्रत्ययादन्यपदार्थत्वाच्चानेकशेषः । ७५० प्रथममध्यमोत्तमानामेकशेषोऽसरूपत्वात् ।
७५१ द्विवचनबहुवचनाप्रसिद्धिश्चैकार्थत्वात् । ७५२ नैकार्थ्यम् । ७५३ नैकार्थ्यमिति चेदार-
म्भानर्थक्यम् । ७५४ अशिष्य एकशेष एकेनोक्तत्वात् । ७५५ प्रत्यर्थं शब्दनिवेशादेकेनानेक-
स्याभिधानादप्रत्यर्थमिति चेत्तदपि प्रत्यर्थमेव । ७५६ यावतामभिधानं तावतां प्रयोगो
न्याय्यः । ७५७ यावतामभिधानं तावतां प्रयोगो न्याय्य इति चेदेकेनानेकस्याभिधानम् ।
७५८ एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः । ७५९ एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इति
चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य नग्रोधप्रयोगः । ७६० अभिधानं पुनः स्वाभाविकम् । ७६१
उभयदर्शनाच्च । ७६२ आकृत्यभिधानाद्वैकं विभक्तौ वाजप्यायनः । ७६३ प्रख्याविशेषात् ।
७६४ अन्यपवर्गगतेश्च । ७६५ ज्ञायते चैकोपदिष्टम् । ७६६ धर्मशास्त्रं च तथा । ७६७
अस्ति चैकमनेकाधिकरणस्थं युगपत् । ७६८ इतीन्द्रवद्विषयः । ७६९ नैकमनेकाधिकर-
णस्थं युगपदिति चेत्तथैकशेषे । ७७० द्रव्याभिधाने ह्याकृत्यसंप्रत्ययः । ७७१ तत्रासर्वद्रव्य-
गतिः । ७७२ चोदनायां चैकस्योपाधिवृत्तेः । ७७३ द्रव्याभिधानं व्याडिः । ७७४ तथा च
लिङ्गवचनसिद्धिः । ७७५ चोदनासु च तस्यारम्भात् । ७७६ न चैकमनेकाधिकरणस्थं युग-
पत् । ७७७ विनाशे प्रादुर्भावे च सर्वं तथा स्यात् । ७७८ अस्ति च वैरूप्यम् । ७७९ तथा
च विग्रहः । ७८० व्यर्थेषु च मुक्तसंशयम् । ७८१ लिङ्गवचनसिद्धिर्गुणस्यानित्यत्वात् ।
७८२ गुणवचनवद्वा । ७८३ अधिकरणगतिः साहचर्यात् । ७८४ न चैकमनेकाधिकरणस्थं
युगपदित्यादित्यवद्विषयः । ७८५ अविनाशोऽनाश्रितत्वात् (नैकात्म्यात्) । ७८६ वैरूप्य-
विग्रहौ द्रव्यभेदात् । ७८७ व्यर्थेषु सामान्यात्सिद्धम् ॥

२ । ६८ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ९३४ ॥ ७८८ असरूपाणां युवस्थविरस्त्रीपुंसानां
विशेषस्याविवक्षितत्वात्सामान्यस्य विवक्षितत्वात्सिद्धम् । ७८९ ब्राह्मणवत्साब्राह्मणीवत्सयो-
र्लिङ्गस्य विभक्तिपरस्य विशेषवाचकत्वादनेकशेषः ॥

२ । ६९ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ९३५ ॥ ७९० प्रधाने कार्यसंप्रत्य-
याच्छेषः । ७९१ आकृतिवाचित्वादेकवचनम् ॥

२ । ६८, ७०-७१ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ९३४ । पिता मात्रा ९३६ । श्वशुरः
श्वश्र्वा ९३७ ॥ ७९२ भ्रातृपुत्रपितृश्वशुराणां कारणाद्द्रव्ये शब्दनिवेशः । ७९३ भ्रातृपुत्र-
पितृश्वशुराणां कारणाद्द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् । ७९४ दर्शनं वै
हेतुः । ७९५ दर्शनं हेतुरिति चेत्तुल्यम् । ७९६ न वा एष लोके संप्रत्ययः । ७९७ तद्विषयं
च । ७९८ अन्यत्रापि तद्विषयदर्शनात् ॥

२।७२ त्यदादीनि सर्वैर्नित्यम् ९३८॥ ७९९ त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि। ८०० अद्वन्द्वतत्पुरुषविशेषणानाम् । ८०१ त्यदादीनां सामान्यार्थत्वात् । ८०२ परस्य चोभयवाचित्वात् । ८०३ पूर्वशेषदर्शनाच्च । ८०४ सामान्यविशेषवाचिनोश्च द्वन्द्वाभावात्सिद्धम् ॥

२।७३ ग्राम्यपशुसंघेष्वतरुणेषु स्त्री ९३९ ॥ ८०५ अनेकशफेष्विति वक्तव्यम् ॥

३।१ भूवादयो धातवः १८ ॥ ८०६ भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । ८०७ पाठेन धातुसंज्ञायां समानशब्दप्रतिषेधः । ८०८ परिमाणग्रहणं च । ८०९ क्रियावचन उपसर्गप्रत्ययप्रतिषेधः । ८१० संघातेनार्थगतेः । ८११ अस्तिभवतिविद्यतीनां धातुत्वम् । ८१२ प्रत्ययार्थस्याव्यतिरेकात्प्रकृत्यन्तरेषु । ८१३ धातोश्चार्थाभेदात्प्रत्ययान्तरेषु । ८१४ सिद्धं त्वन्वयव्यतिरेकाभ्याम् । ८१५ क्रियाविशेषक उपसर्गः । ८१६ भाववचने तदर्थप्रत्ययप्रतिषेधः । ८१७ इतरेतराश्रयं च प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः । ८१८ सिद्धं तु नित्यशब्दत्वादनाश्रित्य भाववचनत्वं प्रत्ययः । ८१९ प्रथमभावग्रहणं च । ८२० भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः । ८२१ स्वरानुबन्धज्ञापनाय च ॥

३।२ उपदेशेऽजनुनासिक इत् ३ ॥ ८२२ इत्संज्ञायां सर्वप्रसङ्गोऽविशेषात् । ८२३ सिद्धं तूपदेशनेऽनुनासिकवचनात् ॥

३।३ हलन्त्यम् १ ॥ ८२४ हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वात् । ८२५ सिद्धं तु व्यवसितान्त्यत्वात् । ८२६ लकारस्यानुबन्धाज्ञापितत्वाद्धल्ग्रहणाप्रसिद्धिः । ८२७ सिद्धं तु लकारनिर्देशात् । ८२८ एकशेषनिर्देशाद्वा । ८२९ प्रातिपदिकप्रतिषेधोऽकृत्तद्धिते । ८३० इदर्थाभावात्सिद्धम् ॥

३।४ न विभक्तौ तुस्माः १९० ॥ ८३१ विभक्तौ तवर्गप्रतिषेधोऽतद्धिते ॥

३।७ चुटू १८९ ॥ ८३२ चुञ्चुप्चणपोश्चकारप्रतिषेधः । ८३३ इदर्थाभावात्सिद्धम् । ८३४ पित्करणं किमर्थमिति चेत्पर्यायार्थम् । ८३५ इर उपसंख्यानम् । ८३६ अवयवग्रहणात्सिद्धम् । ८३७ अवयवग्रहणादिति चेदिदिद्विधिप्रसङ्गः ॥

३।९ तस्य लोपः ६२ ॥ ८३८ इतो लोपे णल्क्त्वानिष्ठासूपसंख्यानमित्प्रतिषेधात् । ८३९ सिद्धं तु णलादीनां ग्रहणप्रतिषेधात् । ८४० निर्दिष्टलोपाद्वा । ८४१ तत्र तुस्मानां प्रतिषेधः । ८४२ न वोच्चारणसामर्थ्यात् । ८४३ अनुबन्धलोपे भावाभावयोर्विप्रतिषेधादप्रसिद्धिः । ८४४ सिद्धं त्वनवादन्यायेन । ८४५ भावो हि कार्यार्थोऽनन्यार्थो लोपः । ८४६ एकान्तस्तत्रोपलब्धेः । ८४७ तत्रासरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोऽनाकारान्तत्वात् । ८४८ अनेकान्ते वृत्तिविशेषः । ८४९ अनन्तर इति चेत्पूर्वपरयोरित्कृतप्रसङ्गः । ८५० सिद्धं तु व्यवसितपाठात् । ८५१ इतरथा ह्येकान्तेऽपि संदेहः । ८५२ वृत्ताद्वा ॥

३।१० यथासंख्यमनुदेशः समानाम् १२८ ॥ ८५३ संज्ञासमासनिर्देशात्सर्वप्रसङ्गोऽनुदेशस्य तत्र यथासंख्यवचनं नियमार्थम् । ८५४ संज्ञासमासनिर्देशः पृथग्विभक्तिसंख्यानुच्चारणार्थः । ८५५ प्रकरणे च सर्वसंप्रत्ययार्थः । ८५६ संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्यायवायाव एच इत्यनिर्देशः । ८५७ अर्थतश्चेल्लुटो नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः । ८५८ आत्मनेपदविधिनिष्ठासार्वधातुकाद्विग्रहणेषु । ८५९ एङः पूर्वत्वे प्रतिषेधः । ८६० अतिप्रसङ्गो गुणवृद्धिप्रतिषेधे क्ङिति । ८६१ ङदि कूले रुजिवहोः । ८६२ तच्छी-

लादिषु धातुनिग्रहणेषु । ८६३ घञादिषु द्विग्रहणेषु । ८६४ अवे तॄस्त्रोः करणाधिकरणयोः । ८६५ कर्तृकर्मणोश्च भूकृञोः । ८६६ अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि । ८६७ कृभ्वोः क्त्वाणमुलौ । ८६८ अधीयानविदुषोश्छन्दोब्राह्मणानि । ८६९ रोपधेतोः पथिदूतयोः । ८७० तत्र भवस्तस्य व्याख्यानः क्रतुयज्ञेभ्यः । ८७१ संघादिष्वञ्प्रभृतयः । ८७२ वेशोयशआदेर्भगाद्यल्खौ । ८७३ ङसिङसोः ल्यप्त्यात्परस्य । ८७४ न वा समानयोगवचनात् । ८७५ तस्य दोषो विदो लटो वा । ८७६ ध्माधेटोर्नाडीमुष्ट्योश्च । ८७७ खलगोरथादिनित्रकट्यचश्च । ८७८ सिन्ध्वपकराभ्यां कन् अणञौ च । ८७९ युष्मदस्मदोश्चादेशाः ॥

३ । ११ स्वरितेनाधिकारः ४६ ॥ ८८० अधिकारः प्रतियोगं तस्यानिर्देशार्थः । ८८१ न वा निर्दिश्यमानाधिकृतत्वाद्यथा लोके । ८८२ अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा । ८८३ अधिकारपरिमाणाज्ञानं तु । ८८४ अधिकारपरिमाणज्ञानार्थं तु । ८८५ यावतिथोऽलनुबन्ध-स्तावतो योगानिति वचनात्सिद्धम् । ८८६ भूयसि प्राग्वचनम् ॥

३ । १२ अनुदात्तङित आत्मनेपदम् २१५७ ॥ ८८७ विकरणेभ्यः प्रतिषेधः । ८८८ आत्मनेपदवचनं नियमार्थम् । ८८९ लविधानाद्विहितम् । ८९० तत्र प्रत्ययनियमे शेषवचनं परस्मैपदस्यानिवृत्तत्वात् । ८९१ क्यष आत्मनेपदवचनं तस्यान्यत्र नियमात् । ८९२ प्रकृत्यर्थ-नियमेऽन्याभावः । ८९३ शेषवचनं च । ८९४ कर्तरि चात्मनेपदविषये परस्मैपदप्रतिषेधार्थम् ॥

३ । १४ कर्तरि कर्मव्यतिहारे २६८० ॥ ८९५ क्रियाव्यतिहार इति वक्तव्यम् । ८९६ कर्मव्यतिहारादिषु कर्तृग्रहणं भावकर्मनिवृत्त्यर्थम् । ८९७ न वानन्तरस्य प्रतिषेधात् ॥

३ । १५ न गतिहिंसार्थेभ्यः २६८१ ॥ ८९८ प्रतिषेधे हसादीनामुपसंख्यानम् । ८९९ हरि-वह्योरप्रतिषेधः ॥

३ । १६ इतरेतरान्योन्योपपदाच्च २६८२ ॥ ९०० परस्परोपपदाच्च ॥

३ । १९ विपराभ्यां जेः २६८५ ॥ ९०१ उपसर्गग्रहणम् ॥

३ । २० आङो दोऽनास्यविहरणे २६८६ ॥ ९०२ आङो दोऽव्यसनक्रियस्य । ९०३ स्वाङ्गकर्मकाच्च ॥

३ । २१ क्रीडोऽनुसंपरिभ्यश्च २६८७ ॥ ९०४ समोऽकूजने । ९०५ आगमेः क्षमायाम् । ९०६ शिक्षेर्जिज्ञासायाम् । ९०७ किरतेर्हर्षजीविकाकुलायकरणेषु । ९०८ हरतेर्गतताच्छील्ये । ९०९ आङि नुप्रच्छ्योः । ९१० आशिषि नाथः । ९११ शप उपलम्भने ॥

३ । २२ समवप्रविभ्यः स्थः २६८९ ॥ ९१२ आङः स्थः प्रतिज्ञाने ॥

३ । २४ उदोऽनूर्ध्वकर्मणि २६९१ ॥ ९१३ उद ईहायाम् ॥

३ । २५ उपान्मन्त्रकरणे २६९२ ॥ ९१४ उपाद्देवपूजासंगतकरणयोः । ('उपाद्देव-पूजासंगतकरणमित्रकरणपथिष्विति वक्तव्यम्' इत्यपर आह) । ९१५ वा लिप्सायाम् ॥

३ । २७ उद्विभ्यां तपः २६९४ ॥ ९१६ स्वाङ्गकर्मकाच्च ॥

३ । २८ आङो यमहनः २६९५ ॥ ९१७ स्वाङ्गकर्मकाच्च ॥

३ । २९ समो गम्यृच्छिभ्याम् २६९९ ॥ ९१८ समो गमादिषु विदिप्रच्छिस्वरती-नामुपसंख्यानम् । ९१९ अर्तिश्रुदृशिभ्यश्च । ९२० उपसर्गादस्यत्यूह्योर्वावचनम् ॥

३ । ४० आङ उद्गमने २७१३ ॥ ९२१ ज्योतिषामुद्गमने ॥

३ । ५१ अवाद्ग्रः २७२४ ॥ ९२२ अवाद्ग्रो गिरतेः ॥

३ । ५८ नानोर्ज्ञः २७३२ ॥ ९२३ अनोर्ज्ञः प्रतिषेधे सकर्मकवचनम् । ९२४ न वाकर्मकस्योत्तरेण विधानात् । ९२५ प्रतिषेधः पूर्वस्य च ॥

३ । ६० शदेः शितः २३६२ ॥ ९२६ शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदाभावः । ९२७ सिद्धं तु लडादीनामात्मनेपदवचनात् । ९२८ उपसर्गपूर्वविधानेऽड्व्यवाय उपसंख्यानम् । ९२९ नित्यत्वाद्धादेशस्यात्मनेपदेऽडागम इति चेदटोऽपि नित्यनिमित्तत्वादात्मनेपदाभावः । ९३० तस्मादुपसंख्यानम् ॥

३ । ६२ पूर्ववत्सनः २७३४ ॥ ९३१ पूर्ववत्सन इति शादिम्रियत्यर्थम् । ९३२ इतरथा हि ताभ्यां सन्नन्ताभ्यामात्मनेपदप्रतिषेधः । ९३३ पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेद्धुपादिष्वप्रसिद्धिः । ९३४ सिद्धं तु पूर्वस्य लिङ्गातिदेशात् । ९३५ कृञादिषु तु लिङ्गप्रतिषेधः । ९३६ प्रत्ययग्रहणं नियमार्थम् । ९३७ तत्र हेतुमण्णिचः प्रतिषेधः ॥

३ । ६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु २७३५ ॥ ९३८ स्वराद्युपसृष्टादिति वक्तव्यम् । ९३९ स्वराद्यन्तोपसृष्टादिति वक्तव्यम् ॥

३ । ६५ समः क्ष्णुवः २७३६ ॥ ९४० समः क्ष्णुवः सकर्मकार्थम् ॥

३ । ६६ भुजोऽनवने २७३७ ॥ ९४१ अनवनकौटिल्ययोरिति वक्तव्यम् ॥

३ । ६७ णेरणौ यत्कर्म णौ चेत्स कर्ताऽनाध्याने २७३८ ॥ ९४२ णेरात्मनेपदविधानेऽण्यन्तस्य कर्मणस्तत्रोपलब्धिः । ९४३ इतरथा हि सर्वप्रसङ्गः । ९४४ कर्मकर्तृत्वात्सिद्धमिति चेद्यक्चिणोर्निवृत्त्यर्थं वचनम् । ९४५ न वा यक्चिणोः प्रतिषेधात् । ९४६ इतरथा हि यत्र नियमस्ततोऽन्यत्र प्रतिषेधः । ९४७ आत्मनेपदस्य च । ९४८ आत्मनेपदप्रतिषेधार्थं तु । ९४९ आत्मनः कर्मत्वे प्रतिषेधः । ९५० न वा ण्यन्तेऽन्यस्य कर्तृत्वात् ॥

३ । ७८ शेषात्कर्तरि परस्मैपदम् २१५९ ॥ ९५१ शेषवचनं पञ्चम्या चेदर्थे प्रतिषेधः । ९५२ सप्तम्या चेत्प्रकृतेः । ९५३ सिद्धं तूभयनिर्देशात् । ९५४ कर्तृग्रहणमनुपराद्यर्थम् ॥

३ । ७९ अनुपराभ्यां कृञः २७४५ ॥ ९५५ परस्मैपदप्रतिषेधात्कृञादिषु वचनम् । ९५६ तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् । ९५७ न वा द्युतादिभ्यो वावचनात् । ९५८ आत्मनेपदानियमे वा प्रतिषेधः ॥

३ । ८७ निगरणचलनार्थेभ्यश्च २७५३ ॥ ९५९ अदेः प्रतिषेधो वक्तव्यः ॥

३ । ८८ अणावकर्मकाच्चित्तवत्कर्तृकात् २७५४ ॥ ९६० अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदवचनम् । ९६१ सिद्धं त्वनस्मिण्णाविति वचनात् ॥

३ । ८९ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः २७५५ ॥ ९६२ पादिषु धेट उपसंख्यानम् ॥

४ । १ आ कडारादेका संज्ञा २३२ ॥ ९६३ अन्यत्र संज्ञासमावेशान्नियमार्थं वचनम् । ९६४ तत्रैकसंज्ञाधिकारे तद्वचनम् । ९६५ अङ्गसंज्ञया भपदसंज्ञयोरसमावेशः । ९६६ कर्म-

---

१ इदं काशिकायां कौमुद्यां च व्याख्यातम् । भाष्यकृता 'गतिबुद्धि-' (१ । ४ । ५२) इति सूत्रे 'सर्वमेव प्रत्यवसानकार्यमदेर्न भवतीति वक्तव्यं परस्मैपदमपि । इदमेकमिष्यते 'क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः इदमेषां जग्धम्' इति वदताङ्गीकृतमेव ॥

धारये तत्पुरुषग्रहणम् । ९६७ तत्पुरुषत्वे द्विगुत्वग्रहणम् । ९६८ गुरुलघुसंज्ञे नदीघिसंज्ञे ।
९६९ परस्मैपदसंज्ञा पुरुषसंज्ञा । ९७० परवचने सिति पदं भम् । ९७१ गतिबुद्ध्यादीनां
ण्यन्तानां कर्म कर्तृसंज्ञम् । ९७२ शेषवचनं च घिसंज्ञानिवृत्त्यर्थम् । ९७३ न वा संभवात् ।
९७४ ह्रस्वलक्षणा हि नदीसंज्ञा घिसंज्ञायां च गुणः । ९७५ तत्र वचनप्रामाण्यान्नदीसंज्ञायां
घिसंज्ञाभावः । ९७६ आश्रयाभावान्नदीसंज्ञायां घिसंज्ञानिवृत्तिरिति चेद्यणादेशाभावः । ९७७
नद्याश्रयत्वाद्यणादेशस्य ह्रस्वस्य नदीसंज्ञाभावः । ९७८ बहुव्रीह्यर्थं तु । ९७९ प्रयोजनम-
व्ययीभावोपमानद्विगुकृल्लोपेषु । ९८० तत्र शेषवचनाद्दोषः संख्यासमानाधिकरणनञ्समासेषु
बहुव्रीहिप्रतिषेधः । ९८१ कृल्लोपे च शेषवचनात्प्रादिभिर्न बहुव्रीहिः । ९८२ एकसंज्ञाधि-
कारे विप्रतिषेधाद्बहुव्रीहिः । ९८३ एकसंज्ञाधिकारे विप्रतिषेधाद्बहुव्रीहिरिति चेत् कार्थे प्रति-
षेधः । ९८४ तत्पुरुष इति चेदन्यत्र कार्थात्प्रतिषेधः । ९८५ सिद्धं तु प्रादीनां कार्थे तत्पु-
रुषवचनात् । ९८६ प्रयोजनं ह्रस्वसंज्ञा दीर्घप्लुतौ । ९८७ तिङ्सार्वधातुकं लिङ्लिटोरार्धधातु-
कम् । ९८८ अपत्यं वृद्धं युवा । ९८९ घि नदी । ९९० लघु गुरु । ९९१ पदं भम् । ९९२
अपादानमुत्तराणि । ९९३ क्रुधद्रुहोरुपसृष्टयोः कर्म संप्रदानम् । ९९४ करणं पराणि ।
९९५ अधिकरणं कर्म । ९९६ अधिकरणं कर्ता । ९९७ अभ्युपसृष्टं कर्म । ९९८
गत्युपसर्गसंज्ञे कर्मप्रवचनीयसंज्ञा । ९९९ परस्मैपदमात्मनेपदम् । १००० समाससंज्ञा च ।
१००१ अर्थवत्प्रातिपदिकम् । १००२ गुणवचनं तु । १००३ समासकृत्तद्धिताव्ययसर्वनामा-
सर्वलिङ्गा जातिः । १००४ संख्या । १००५ डु च । १००६ एकद्रव्योपनिवेशिनी संज्ञा ॥

४ । २ विप्रतिषेधे परं कार्यम् १७५ ॥ १००७ द्वौ प्रसङ्गावन्यार्थावेकस्मिन्स विप्रतिषेधः ।
१००८ एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तिरुभयप्रसङ्गः । १००९ तुल्यादिभिस्तुल्यम् । १०१०
अनवयवप्रसङ्गात्प्रतिपदं विधेश्च । १०११ अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात् । १०१२ तत्र प्रति-
पत्त्यर्थं वचनम् । १०१३ तव्यदादीनां त्वप्रसिद्धिः । १०१४ अन्तरङ्गं च । १०१५ प्रयोजनं
यणेकादेशत्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः । १०१६ इण्ङ्शीनामाद्गुणः सवर्णदीर्घ-
त्वात् । १०१७ न वा सवर्णदीर्घत्वस्यानवकाशत्वात् । १०१८ ऊङापोरेकादेश ईत्वलोपाभ्याम् ।
१०१९ आत्वनपुंसकोपसर्जनह्रस्वत्वान्ययवायविकादेशतुग्विधिभ्यः । १०२० तुग्यणेकादेशगु-
णवृद्ध्यौत्त्वदीर्घत्वेत्वमुमेत्त्वरीविधिभ्यः । १०२१ अनङनङ्भ्यां चेति वक्तव्यम् । १०२२ इय-
ङादेशो गुणात् । १०२३ उवङादेशश्चेति वक्तव्यम् । १०२४ श्वेः संप्रसारणपूर्वत्वं यणादेशात् ।
१०२५ ह्व आकारलोपात् । १०२६ स्वरो लोपात् । १०२७ प्रत्ययविधिरेकादेशात् । १०२८
यणादेशाश्चेति वक्तव्यम् । १०२९ लादेशो वर्णविधेः । १०३० तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृ-
तिस्वरात् । १०३१ तस्य दोषः पूर्वपदोत्तरपदयोर्वृद्धिस्वरावेकादेशात् । १०३२ यणादेशा-
दियुवौ । १०३३ उसि पररूपाच्च । १०३४ लुग्लोपयणयवायावेकादेशेभ्यः ॥

४ । इंयू स्त्र्याख्यौ नदी २६६ ॥ १०३५ नदीसंज्ञायामाख्याग्रहणं स्त्रीविषयत्वार्थम् ।
१०३६ प्रथमलिङ्गग्रहणं च । १०३७ प्रयोजनं क्विब्लुप्समासाः । १०३८ अवयवस्त्री-
विषयत्वात्सिद्धम् । १०३९ अवयवस्त्रीविषयत्वात्सिद्धमिति चेदियङुवङ्स्थानप्रतिषेधे यण्स्थान-
प्रतिषेधप्रसङ्गोऽवयवस्येयङुवङ्स्थानत्वात् । १०४० सिद्धं त्वङ्गरूपग्रहणाद्यस्याङ्गस्येयुवौ
तत्प्रतिषेधात् । १०४१ ह्रस्वेयुवस्थानप्रवृत्तौ च स्त्रीवचने ॥

४।१३ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् १९९ ॥ १०४२ अङ्गसंज्ञायां तदादिवचनं स्यादिनुमर्थम् । १०४३ मित्सुटोरुपसंख्यानम् । १०४४ सिद्धं तु तदाद्यादिवचनात् । १०४५ तदेकदेशविज्ञानाद्वा सिद्धम् । १०४६ प्रत्ययग्रहणं पदादावप्रसङ्गार्थम् । १०४७ परिमाणार्थं च । १०४८ । सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात् । १०४९ प्रयोजनं धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः । १०५० कृद्ग्रहणे गतिकारकपूर्वस्यापि । १०५१ प्रयोजनं समासतद्धितविधिस्वराः ॥

४।१४ सुप्तिङन्तं पदम् २९ ॥ १०५२ पदसंज्ञायामन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् ॥

४।१७ स्वादिष्वसर्वनामस्थाने २३० ॥ १०५३ नाप्रतिषेधात् । १०५४ अप्राप्तेर्वा १०५५ भुवद्वद्ग्रहो धारयद्ग्रहः पदसंज्ञा ॥

४।१८ यचि भम् २३१ ॥ १०५६ भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः । १०५७ सिद्धमचः स्थानिवत्त्वात् । १०५८ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् । १०५९ वृषण्वस्त्वश्वयोः ॥

४।२० अयस्मयादीनि छन्दसि ३३९० ॥ १०६० उभयसंज्ञान्यपीति वक्तव्यम् ॥

४।२१ बहुषु बहुवचनम् १८७ ॥ १०६१ सुतिङामविशेषविधानाद्दृष्टविप्रयोगत्वाच्च नियमार्थं वचनम् । १०६२ तत्र प्रत्ययनियमेऽव्ययानां पदसंज्ञाभावोऽसुबन्तत्वात् । १०६३ अर्थनियमे सिद्धम् ॥

४।२३ कारके ५३४ ॥ १०६४ कारक इति संज्ञानिर्देशश्चेत्संज्ञिनोऽपि निर्देशः । १०६५ इतरथा ह्यनिष्टप्रसङ्गो ग्रामस्य समीपादागच्छतीत्यकारकस्य । १०६६ कर्मसंज्ञाप्रसङ्गोऽकथितस्य ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । १०६७ अपादानं च वृक्षस्य पर्णं पततीति । १०६८ न वापायस्याविवक्षितत्वात् । १०६९ अन्वर्थमिति चेदकर्तरि कर्तृशब्दानुपपत्तिः । १०७० सिद्धं तु प्रतिकारकं क्रियाभेदात्पचादीनां करणाधिकरणयोः कर्तृभावः । १०७१ अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणक्रियाः प्रधानस्य कर्तुः पाकः । १०७२ द्रोणं पचत्याढकं पचतीति संभवनक्रिया धारणक्रिया चाधिकरणस्य पाकः । १०७३ एधाः पक्ष्यन्त्याविक्लित्तेर्ज्वलिष्यन्तीति ज्वलनक्रिया करणस्य पाकः । १०७४ उद्यमननिपातनानि कर्तुश्छिदिक्रिया । १०७५ यत्तत् न तृणेन तत्परशोश्छेदनम् । १०७६ इतरथा ह्यसितृणयोश्छेदनेऽविशेषः स्यात् । १०७७ अपादानादीनां त्वप्रसिद्धिः । १०७८ न वा स्वतन्त्रपरतन्त्रत्वात्तयोः पर्यायेण वचनं वचनाश्रया च संज्ञा ॥

४।२४ ध्रुवमपायेऽपादानम् ५८६ ॥ १०७९ जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् । १०८० गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुवत्वात् । १०८१ न वाऽध्रौव्यस्याविवक्षितत्वात् ॥

४।२७ वारणार्थानामीप्सितः ५९० ॥ १०८२ वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनात् ॥

४।२९ आख्यातोपयोगे ५९२ ॥ १०८३ आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः । १०८४ अकारकमिति चेदुपयोगवचनानर्थक्यम् ॥

४।३२ कर्मणा यमभिप्रैति स संप्रदानम् ५६९ ॥ १०८५ क्रियाग्रहणमपि कर्तव्यम् । १०८६ कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा ॥

४ । ४८ उपान्वध्याङ्वसः ५४४ ॥ १०८७ वसेरश्यर्थस्य प्रतिषेधः ॥

४ । ४९ कर्तुरीप्सिततमं कर्म ५३५ ॥ १०८८ ईप्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे कर्मसंज्ञाप्रसङ्गः क्रियेप्सितत्वात् । १०८९ न वोभयेप्सितत्वात् ॥

४ । ५१ अकथितं च ५३९ ॥ १०९० दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ १०९१ कथिते लादयश्चेत्स्युः षष्ठीं कुर्यात्तदा गुणे । १०९२ अकारकं ह्यकथितत्वात् । १०९३ कारकं चेत्तु नाकथा । १०९४ कारकं चेद्विजानीयाद्यां यां मन्येत सा भवेत् । १०९५ कथितेऽभिहिते त्वविधिस्त्वमतिर्गुणकर्मणि लादिविधिः सपरे । १०९६ ध्रुवचेष्टितयुक्तिषु चाप्यगुणे तदनल्पमतेर्वचनं स्मरत । १०९७ प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । १०९८ अप्रधाने दुहादीनाम् । १०९९ ण्यन्ते कर्तुश्च कर्मणः । ११०० नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च । द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः ॥ ११०१ सिद्धं वाप्यन्यकर्मणः । ११०२ अन्यकर्मेति चेद्ब्रूयाद्यादीनामविधिर्भवेत् । ११०३ कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । ११०४ देशश्चाकर्मणां कर्मसंज्ञो भवतीति वक्तव्यम् ॥

४ । ५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ ५४० ॥ ११०५ शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद्ध्वयत्यादीनां प्रतिषेधः । ११०६ शृणोत्यादीनां चोपसंख्यानमशब्दक्रियत्वात् । ११०७ शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानम् । ११०८ दृशेः सर्वत्र । ११०९ अदिखादिनीवहीनां प्रतिषेधः । १११० वहेरनियन्तृकर्तृकस्य । ११११ भक्षेरहिंसार्थस्य । १११२ अकर्मकग्रहणे कालकर्मकाणामुपसंख्यानम् । १११३ सिद्धं तु कालकर्मकाणामकर्मकवद्वचनात् ॥

४ । ५३ हृक्रोरन्यतरस्याम् ५४१ ॥ १११४ हृक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानम् ॥

४ । ५४ स्वतन्त्रः कर्ता ५५९ ॥ १११५ स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानमस्वतन्त्रत्वात् । १११६ न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि कारयतीति स्यात् । १११७ नाकुर्वतीति चेत्स्वतन्त्रः ॥

४ । ५५ तत्प्रयोजको हेतुश्च २५७५ ॥ १११८ प्रैषेऽस्वतन्त्रप्रयोजकत्वाद्धेतुसंज्ञाप्रसिद्धिः । १११९ स्वतन्त्रत्वात्सिद्धम् । ११२० स्वतन्त्रत्वात्सिद्धमिति चेत्स्वतन्त्रपरतन्त्रत्वं विप्रतिषिद्धम् ॥

४ । ५६ प्राग्रीश्वरान्निपाताः १९ ॥ ११२१ रीश्वराद्वीश्वरान्मा भूत् । ११२२ कृन्मेजन्तः परोऽपि सः । ११२३ समासेष्वव्ययीभावः । ११२४ लौकिकं चातिवर्तते । ११२५ प्राग्वचनं संज्ञानिवृत्त्यर्थम् ॥

४ । ५८-५९ प्रादयः २१ । उपसर्गाः क्रियायोगे २२ ॥ ११२६ प्रादय इति योगविभागः । ११२७ ११२८ निपातसंज्ञार्थः । ११२९ एकयोगे हि निपातसंज्ञाभावः । ११३० मरुच्छब्दस्योपसंख्यानम् । ११३१ श्रच्छब्दस्योपसंख्यानम् ॥

४ । ६० गतिश्च २३ ॥ ११३२ कारिकाशब्दस्य । ११३३ पुनश्चनसौ छन्दसि । ११३४ गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्तास्तं प्रतीति वचनम् । ११३५ प्रयोजनं घञ्स्वत्वणत्वे ।

११३६ वृद्धिविधौ च धातुग्रहणानर्थक्यम् । ११३७ वद्विधिनस्भावावीत्त्वस्वाङ्गादिस्वरणत्वेषु वचनप्रामाण्यात्सिद्धम् । ११३८ सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेषु ॥

४ । ६१ ऊर्यादिच्विडाचश्च ७६२ ॥ ११३९ कृभ्वस्तियोग इति वक्तव्यम् ॥

४ । ६२ अनुकरणं चानितिपरम् ७६३ ॥ ११४० अनुकरणस्येतिकरणपरत्वप्रतिषेधोऽनिष्टशब्दनिवृत्त्यर्थः ॥

४ । ६९ अन्तरपरिग्रहे ७६६ ॥ ११४१ अन्तःशब्दस्याङ्किविधिसमासणत्वेषूपसंख्यानम् ॥

४ । ७४ साक्षात्प्रभृतीनि च ७७९ ॥ ११४२ साक्षात्प्रभृतिषु च्व्यर्थवचनम् । ११४३ मकारान्तत्वं च गतिसंज्ञानियुक्तम् । ११४४ तत्र च्विप्रतिषेधः । ११४५ न वा पूर्वेण कृतत्वात् ॥

४ । ८० ते प्राग्धातोः २२३० ॥ ११४६ प्राग्धातुवचनं प्रयोगनियमार्थमिति चेदनुकरणस्येतिकरणपरप्रतिषेधोऽनिष्टशब्दनिवृत्त्यर्थः । ११४७ छन्दसि परव्यवहितवचनं च । ११४८ संज्ञानियमे सिद्धम् । ११४९ उभयोरनर्थकं वचनमनिष्टादर्शनात् । ११५० उपसर्जनसंनिपाते तु पूर्वपरव्यवस्थार्थम् ॥

४ । ८४ अनुर्लक्षणे ५४७ ॥ ११५१ अनुर्लक्षणवचनानर्थक्यं सामान्यकृतत्वात् । ११५२ हेत्वर्थं तु वचनम् ॥

४ । ८९ आङ्मर्यादावचने ५९७ ॥ ११५३ आङ्मर्यादाभिविध्योरिति वक्तव्यम् ॥

४ । ९९ लः परस्मैपदम् २१५५ ॥ ११५४ लादेशे परस्मैपदग्रहणं पुरुषबाधितत्वात् । ११५५ इह वचने हि संज्ञाबाधनम् । ११५६ सिचि वृद्धौ तु परस्मैपदग्रहणं ज्ञापकं पुरुषाबाधकत्वस्य ॥

४ । १०१ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः २१६० ॥ ११५७ प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहणं समसंख्यार्थम् । ११५८ आनुपूर्व्यवचनं च । ११५९ न वैकशेषनिर्देशात् ॥

४ । १०५,१०७-१०८ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः २१६३। अस्मद्युत्तमः २१६४ । शेषे प्रथमः २१६५ ॥ ११६० युष्मदस्मच्छेषवचनं नियमार्थम् । ११६१ तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् । ११६२ सिद्धं तु युष्मदस्मदोः प्रतिषेधात् । ११६३ युष्मदि मध्यमादस्मद्युत्तमो विप्रतिषेधेन । ११६४ अनेकशेषभावात्तु । ११६५ न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेधः । ११६६ क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्रानेकशेषभावस्य ॥

४ । १०९ परः संनिकर्षः संहिता २८ ॥ ११६७ परः संनिकर्षः संहिता चेद्द्रुतायामसंहितम् । ११६८ तुल्यः संनिकर्षः । ११६९ वर्णकालभूयस्त्वम् । ११७० द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात् । ११७१ शब्दाविरामे प्रतिवर्णमवसानम् । ११७२ द्रुतादाविरामे स्पर्शाघोषसंयोगेऽसंनिधानादसंहितम् । ११७३ एकेन तुल्यः संनिधिः ११७४ पौर्वापर्यमकालव्यपेतं संहिता चेत्पूर्वापराभावादसंहितम् । ११७५ एकैकवर्णवर्तित्वाद्वा उच्चरितप्रध्वंसित्वाच्च वर्णानाम् ॥

४ । ११० विरामोऽवसानम् २७ ॥ ११७६ अभावेऽवसानलक्षण उपर्यभाववचनम् । ११७७

विरामे विरामवचनम् । ११७८ अभावेऽवसानसंज्ञिन्युपर्यभाववचनम् । ११७९ विरामे विरामवचनम् । ११८० भावाविरामभावित्वाच्छब्दस्यावसानलक्षणं न । ११८१ तत्पर इति वा वर्णस्यावसानम् । ११८२ वर्णोऽन्त्यो वावसानम् । ११८३ संहितावसानयोर्लोकविदितत्वात्सिद्धम् ॥

इति प्रथमोऽध्यायः ।

द्वितीयोऽध्यायः ।

१ । १ समर्थः पदविधिः ६४७ ॥ ११८४ पृथगर्थानामेकार्थीभावः समर्थवचनम् । ११८५ अर्थानादेशनात् । ११८६ तत्र लघ्वर्थम् । ११८७ असंभवः खल्वप्यर्थादेशनस्य । ११८८ अप्रवृत्तिः खल्वप्यर्थादेशनस्य । ११८९ वावचनानर्थक्यं च स्वभावसिद्धत्वात् । ११९० संघातस्यैकार्थ्यात्तदवयवसंख्यातः सुबुत्पत्तिः । ११९१ परस्परव्यपेक्षां सामर्थ्यमेके । ११९२ तत्र नानाकारकान्निघातयुष्मदस्मदादेशप्रतिषेधः । ११९३ प्रचये समासप्रतिषेधः । ११९४ समर्थतराणां वा । ११९५ समुदायसामर्थ्याद्वा सिद्धम् । ११९६ समर्थतराणां वा समुदायसामर्थ्यात् । ११९७ आख्यातं साव्ययकारकविशेषणं वाक्यम् । ११९८ आख्यातं सविशेषणम् । ११९९ एकतिङ् । १२०० समानवाक्ये निघातयुष्मदस्मदादेशाः । १२०१ योगे प्रतिषेधश्चादिभिः । १२०२ समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषूपसंख्यानमसमर्थत्वात् । १२०३ राजगवीक्षीरे द्विसमासप्रसङ्गो द्विषष्ठीभावात् । १२०४ सिद्धं तु राजविशिष्टाया गोः क्षीरेण सामर्थ्यात् । १२०५ पदविधौ समर्थवचनं वर्णाश्रये शास्त्र आनन्तर्यविज्ञानात् । १२०६ समर्थाधिकारस्य विधेयसामानाधिकरण्यान्निर्देशानर्थक्यम् । १२०७ सिद्धं तु समर्थानामिति वचनात् । १२०८ एकशेषनिर्देशाद्वा । १२०९ समानाधिकरणेषूपसंख्यानमसमर्थत्वात् । १२१० द्रव्यं पदार्थ इति चेत् । १२११ न वा वचनप्रामाण्यात् । १२१२ लुताख्यातेषु च । १२१३ तदर्थगतेर्वा । १२१४ समासो द्वयोर्द्वयोश्चेद्द्वन्द्वेऽनेकग्रहणम् । १२१५ द्वयोर्द्वयोः समास इति चेन्न बहुषु द्वित्वाभावात् । १२१६ समासान्तप्रतिषेधश्च । १२१७ अविशेषेण बहुव्रीहावनेकपदप्रसङ्गः । १२१८ तत्र स्वरसमासान्तपुंवद्भावेषु दोषः । १२१९ न वावयवतत्पुरुषत्वात् । १२२० तस्यान्तोदात्तत्वं विप्रतिषेधात् । १२२१ निमित्तिस्वरबलीयस्त्वाद्वा । १२२२ एकशितिपात्स्वरवचनं तु ज्ञापकं निमित्तिस्वरबलीयस्त्वस्य ॥

१ । २ सुबामन्त्रिते पराङ्गवत्स्वरे ३६५६ ॥ १२२३ आमन्त्रितस्य पराङ्गवद्भावे षष्ठ्यामन्त्रितकारकवचनम् । १२२४ तन्निमित्तग्रहणं वा । १२२५ अवचने हि सुबन्तमात्रप्रसङ्गः । १२२६ सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यानमनन्तरत्वात् । १२२७ स्वरेऽवधारणाच्च । १२२८ परमपि च्छन्दसि पूर्वस्याङ्गवद्भवतीति वक्तव्यम् । १२२९ अव्ययप्रतिषेधश्च । १२३० अनव्ययीभावस्य । १२३१ स्वरेऽवधारणं सुब्लोपार्थम् । १२३२ न वा सुबन्तैकान्तत्वात् । १२३३ प्रातिपदिकैकान्तस्तु सुब्लोपे ॥

१ । ३ प्राक्कडारात्समासः ६४८ ॥ १२३४ प्राग्वचनं संज्ञानिवृत्त्यर्थम् ॥

१ । ४ सह सुपा ६४९ ॥ १२३५ सहवचनं पृथगसमासार्थम् । १२३६ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ॥

१ । १० अक्षशलाकासंख्याः परिणा ६६४ ॥ १२३७ अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । १२३८ एकत्वेऽक्षशलाकयोः । १२३९ कितवव्यवहारे च ॥

१ । १७ तिष्ठद्गुप्रभृतीनि च ६७१ ॥ १२४० तिष्ठद्गु कालविशेषे । १२४१ खलेयवादीनि प्रथमान्तान्यपदार्थे ॥

१ । १८ पारेमध्ये षष्ठ्या वा ६७२ ॥ १२४२ पारेमध्ये षष्ठ्या वावचनम् । १२४३ अवचने हि षष्ठीसमासाभावो यथैकदेशिप्रधाने । १२४४ एकारान्तनिपातनं च ॥

१ । २० नदीभिश्च ६७४ ॥ १२४५ नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिषेधः । १२४६ नदीभिः संख्यायाः समाहारेऽव्ययीभावो वक्तव्यः ॥

१ । २४ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ६८६ ॥ १२४७ श्रितादिषु गमिगाम्यादीनामुपसंख्यानम् । १२४८ श्रितादिभिरहीने द्वितीयासमासवचनानर्थक्यं बहुव्रीहिकृतत्वात् । १२४९ अहीने द्वितीयास्वरवचनानर्थक्यं च । १२५० जातिस्वरप्रसङ्गस्तु । १२५१ तत्र जातादिषु वावचनात्सिद्धम् ॥

१ । २९ अत्यन्तसंयोगे च ६९१ ॥ १२५२ अत्यन्तसंयोगे समासस्याविशेषवचनात् क्तेन समासवचनानर्थक्यम् । १२५३ अनत्यन्तसंयोगार्थं तु ॥

१ । ३० तृतीया तत्कृतार्थेन गुणवचनेन ६९२ ॥ १२५४ तृतीयासमासेऽर्थग्रहणमनर्थकमर्थगतिर्निर्वचनात् । १२५५ निर्देक्ष्यामीति चेत्तृतीयार्थनिर्देशोऽपि ॥

१ । ३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ६९३ ॥ १२५६ पूर्वादिष्ववरस्योपसंख्यानम् ॥

१ । ३२ कर्तृकरणे कृता बहुलम् ६९४ ॥ १२५७ कर्तृकरणे कृता क्तेन ॥

१ । ३३ कृत्यैरधिकार्थवचने ६९५ ॥ १२५८ कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यते । १२५९ साधनं कृतेति वा पादहारकाद्यर्थम् । १२६० 'कृत्यग्रहणे यण्ण्यतोर्ग्रहणम्' इति काशिका ॥

१ । ३४-३५ अन्नेन व्यञ्जनम् ६९६ । भक्ष्येण मिश्रीकरणम् ६९७ ॥ १२६१ अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणमित्यसमर्थसमासः । १२६२ कारकाणां क्रियया सामर्थ्यात् । १२६३ वचनप्रामाण्यादिति चेन्नानाकारकाणां प्रतिषेधः । १२६४ सिद्धं तु समानाधिकरणाधिकारात्तृतीयापूर्वपद उत्तरपदलोपश्च । १२६५ षष्ठीसमासश्च युक्तपूर्णान्तः । १२६६ न वासमासेऽदर्शनात् । १२६७ युक्तार्थसंप्रत्ययाच्च सामर्थ्यम् । १२६८ संप्रत्ययाच्च तदर्थाध्यवसानम् । १२६९ संप्रतीयमानार्थलोपे ह्यनवस्था ॥

१ । ३६ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ६९८ ॥ १२७० चतुर्थी तदर्थमात्रेण चेत्सर्वप्रसङ्गोऽविशेषात् । १२७१ बलिरक्षिताभ्यां चानर्थकं वचनम् । १२७२ विकृतिः प्रकृत्येति चेदश्वघासादीनामुपसंख्यानम् । १२७३ अर्थेन नित्यसमासवचनम् । १२७४ सर्वलिङ्गता च ॥

१ । ३७ पञ्चमी भयेन ६९९ ॥ १२७५ भयभीतभीतिभीभिरिति वक्तव्यम् । १२७६ भयनिर्गतजुगुप्सुभिरिति वक्तव्यम् ॥

१ । ४० सप्तमी शौण्डैः ७१७ ॥ १२७७ शौण्डादिभिरिति वक्तव्यम् ॥

१ । ४२ ध्वाङ्क्षेण क्षेपे ७१९ ॥ १२७८ ध्वाङ्क्षेणेत्यर्थग्रहणम् ॥

१ । ४३ कृत्यैर्ऋणे ७२० ॥ १२७९ कृत्यैर्नियोगे यद्ग्रहणम् ॥

१ । ५१ तद्धितार्थोत्तरपदसमाहारे च ७५८ ॥ १२८० द्विगुसंज्ञा प्रत्ययोत्तरपदयोश्चे-दितरेतराश्रयत्वादप्रसिद्धिः । १२८१ अर्थे चेत्तद्धितानुत्पत्तिर्बहुव्रीहिवत् । १२८२ समासतद्धितविधाविति चेदन्यत्र समाससंज्ञाभावः । १२८३ सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् । १२८४ द्विगोर्वा लुग्वचनं ज्ञापकं तद्धितोत्पत्तेः । १२८५ समाहारसमूहयोरविशेषात्समाहार-ग्रहणानर्थक्यं तद्धितार्थेन कृतत्वात् । १२८६ अभिधानार्थं तु । १२८७ द्वन्द्वतत्पुरुषयोरुत्तर-पदे नित्यसमासवचनम् । १२८८ उत्तरपदेन परिमाणिना द्विगोः समासवचनम् । १२८९ अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदप्रसिद्धिः । १२९० सर्वत्र मत्वर्थे प्रतिषेधः ॥

१ । ५५ उपमानानि सामान्यवचनैः ७३४ ॥ १२९१ उपमानसमासे गुणवचनस्य विशेषभाक्त्वात्सामान्यवचनाप्रसिद्धिः । १२९२ न वा श्यामत्वस्योभयत्र भावात्तद्वाचकत्वाच्च शब्दस्य सामान्यवचनप्रसिद्धिः ॥

१ । ५७ विशेषणं विशेष्येण बहुलम् ७३६ ॥ १२९३ विशेषणविशेष्ययोरुभयविशेषण-त्वादुभयोश्च विशेष्यत्वादुपसर्जनाप्रसिद्धिः । १२९४ न वान्यतरस्य प्रधानभावात्तद्विशेषकत्वा-च्चापरस्योपसर्जनप्रसिद्धिः ॥

१ । ५८ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ७३७ ॥ १२९५ बहुलव-चनस्याकृत्स्नत्वादुत्तरत्रानुक्रमणसामर्थ्यम् ॥

१ । ५९ श्रेण्यादयः कृतादिभिः ७३८ ॥ १२९६ श्रेण्यादिषु च्व्यर्थवचनम् ॥

१ । ६० क्तेन नञ्विशिष्टेनानञ् ७३९ ॥ १२९७ नञ्विशिष्टे समानप्रकृतिवचनम् । १२९८ अनञिति च प्रतिषेधो वक्तव्यः । १२९९ नुडिडधिकेन च । १३०० कृतापकृतादीनां चोपसंख्यानम् । १३०१ सिद्धं तु क्तेन विसमाप्तावनञ् । १३०२ गतप्रत्यागतादीनां चोप-संख्यानम् ॥

१ । ६९ वर्णो वर्णेन ७५० ॥ १३०३ वर्णेन तृतीयासमास एतत्प्रतिषेधे वर्णग्रहणम् । १३०४ समानाधिकरणे द्विर्वर्णग्रहणम् । १३०५ समानाधिकरणाधिकारे प्रधानोपसर्जनानां परं परं विप्रतिषेधेन । १३०६ समानाधिकरणसमासाद्बहुव्रीहिः । १३०७ कदाचित्कर्मधारयः सर्व-धनाद्यर्थः । १३०८ पूर्वपदातिशय आतिशयिकाद्बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः । १३०९ उत्तर-पदातिशय आतिशयिको बहुव्रीहेर्वद्धाढ्यतराद्यर्थः । १३१० समानाधिकरणाधिकारे शाकपा-र्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च ॥

१ । ७१ चतुष्पादो गर्भिण्या ७५३ ॥ १३११ चतुष्पाज्जातिरिति वक्तव्यम् ॥

२ । ३ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ७१४ ॥ १३१२ द्वितीयादीनां विभाषा-प्रकरणे विभाषावचनं ज्ञापकमवयवविधाने सामान्यविधानाभावस्य ॥

२ । ५ कालाः परिमाणिना ७१६ ॥ १३१३ कालस्य येन समासस्तस्यापरिमाणित्वाद-निर्देशः । १३१४ सिद्धं तु कालपरिमाणं यस्य स कालस्तेन । १३१५ एकवचनद्विगोश्चोप-संख्यानम् ॥

२ । ७ ईषदकृता ७५५ ॥ १३१६ ईषद्गुणवचनेन ॥

२ । ८ षष्ठी ७०२ ॥ १३१७ कृद्योगा च । १३१८ तत्स्थैश्च गुणैः । १३१९ न तु तद्विशेषणैः ॥

२ । १० न निर्धारणे ७०४ ॥ १३२० प्रतिपदविधाना च ॥

२ । १४ कर्मणि च ७०८ ॥ १३२१ कर्मणीति षष्ठीनिर्देशश्चेदकर्तरि कृता समासवचनम् । १३२२ तृजकाभ्यां चानर्थकः प्रतिषेधः । १३२३ क्तनिर्देशोऽसमर्थत्वादप्रतिषेधः । १३२४ प्रतिषेध्यमिति चेत्कर्तर्यपि प्रतिषेधः । १३२५ पूजायां च प्रतिषेधानर्थक्यम् । १३२६ तस्मादुभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधः ।

२ । १८ कुगतिप्रादयः ७६१ ॥ १३२७ प्रादिप्रसङ्गे कर्मप्रवचनीयप्रतिषेधः । १३२८ स्वतेप्रतिषेधश्च । १३२९ सिद्धं तु क्ताङ्स्वतिदुर्गतिवचनात् । १३३० प्रादयः क्तार्थे । ('१३३१ स्वती पूजायाम् । १३३२ दुर्निन्दायाम् । १३३३ आङीषदर्थे । १३३४ कुः पापार्थे' इति सौनागानां पाठः) । १३३५ प्रादयो गताद्यर्थे प्रथमया । १३३६ अत्यादयः क्रान्ताद्यर्थे द्वितीयया । १३३७ अवादयः क्रुष्टाद्यर्थे तृतीयया । १३३८ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या । १३३९ निरादयः क्रान्ताद्यर्थे पञ्चम्या । १३४० अव्ययं प्रवृद्धादिभिः । १३४१ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च । १३४२ उदात्तवता तिङा गतिमता चाव्ययं समस्यत इति वक्तव्यम् ॥

२ । १९ उपपदमतिङ् ७८२ ॥ १३४३ उपपदमतिङिति तदर्थप्रतिषेधः । १३४४ क्रियाप्रतिषेधो वा । १३४५ षष्ठीसमासादुपपदसमासो विप्रतिषेधेन । १३४६ न वा षष्ठीसमासाभावादुपपदसमासः ॥

२ । २३ शेषो बहुव्रीहिः ८२९ ॥ १३४७ शेषवचनं पदतश्चेन्नाभावात् । १३४८ अर्थतश्चेदविशेषात् ॥

२ । २४ अनेकमन्यपदार्थे ८३० ॥ १३४९ अनेकवचनमुपसर्जनार्थम् । १३५० न वैकविभक्तित्वात् । १३५१ पदार्थाभिधानेऽनुप्रयोगानुपपत्तिरभिहितत्वात् । १३५२ न वानभिहितत्वात् । १३५३ सामान्याभिधाने हि विशेषानभिधानम् । १३५४ विभक्त्यर्थाभिधानेऽद्रव्यस्य लिङ्गसंख्योपचारानुपपत्तिः । १३५५ सिद्धं तु यथा गुणवचनेषु । १३५६ बहुव्रीहिः समानाधिकरणानाम् । १३५७ अव्ययानां च । १३५८ सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च । १३५९ समुदायविकारषष्ठ्याश्च । १३६० प्रादिभ्यो धातुजस्य वा । १३६१ नञोऽस्त्यर्थानाम् । १३६२ न वानभिधानादसमानाधिकरणेषु संज्ञाभावः । १३६३ अर्थनियमे मत्वर्थग्रहणम् । १३६४ तथा चोत्तरस्य वचनार्थः । १३६५ कर्मवचनेनाप्रथमायाः । १३६६ कर्तृवचनेनापि । १३६७ सुबधिकारेऽस्तिक्षीरादिवचनम् । १३६८ न वाव्ययत्वात् ॥

२ । २५ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये ८४३ ॥ १३६९ संख्यासमासे सुजन्तत्वात्संख्याप्रसिद्धिः । १३७० न वासुजन्तत्वात् । १३७१ सुजभावोऽभिहितार्थत्वात्समासे । १३७२ अंशिभ्यः संख्योत्तरपदः संख्येयत्राभिधायित्वात् । १३७३ मत्वर्थे वा पूर्वस्य विधानात् । १३७४ कबभावार्थं वा ॥ त

२ । २६,२८ दिङ्नामान्यन्तराले ८४५ । तेन सहेति तुल्ययोगे ८४८ ॥ १३७५ दिक्समाससहयोगयोश्चान्तरालप्रधानाभिधानात् । १३७६ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यो दक्षिणोत्तरपूर्वाणामित्येवमर्थम् । १३७७ मत्वर्थे वा पूर्वस्य विधानात् । १३७८ कबभावार्थं वा ॥

२ । २७ तत्र तेनेदमिति सरूपे ८४६ ॥ १३७९ तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् ।

१३८० न वैकशेषप्रतिषेधार्थम् । १३८१ पूर्वदीर्घार्थे च । १३८२ मत्त्वर्थे वा पूर्वस्य विधा-
नात् । १३८३ कबभावार्थ वा ॥

२ । २९ चार्थे द्वन्द्वः ९०१ ॥ १३८४ चार्थे द्वन्द्ववचनेऽसमासेऽपि चार्थसंप्रत्ययादनिष्ट-
प्रसङ्गः । १३८५ सिद्धं तु युगपदधिकरणवचने द्वन्द्ववचनात् । १३८६ तत्र पुंवद्भावप्रतिषेधः ।
१३८७ विप्रतिषिद्धे चानुपपत्तिः । १३८८ शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानम् । १३८९
शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानमिति चेद्द्विवचनबहुवचनानुपपत्तिः । १३९० विग्रहे च
युगपद्वचनं ज्ञापकं युगपद्वचनस्य । १३९१ समुदायात्सिद्धम् । १३९२ समुदायात्सिद्धमिति
चेन्नैकार्थत्वात्समुदायस्य । १३९३ नैकार्थ्यम् । १३९४ तयोरनेकार्थत्वाद्बहुवचनप्रसङ्ग इति
चेन्न बहुत्वाभावात् । १३९५ अन्यवाचकेनान्यस्य वचनानुपपत्तिः । १३९६ अन्यवाचकेना-
न्यस्य वचनानुपपत्तिरिति चेत्प्लक्षस्य न्यग्रोधत्वान्न्यग्रोधस्य प्लक्षत्वात्स्वशब्देनाभिधानम् ।
१३९७ कारणाद्द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् । १३९८ दर्शनं हेतुरिति
चेत्तुल्यम् । १३९९ तद्विषयं च । १४०० अन्यत्रापि तद्विषयदर्शनात् । १४०१ एकेनोक्तत्वाद-
परस्य प्रयोगोऽनुपपन्न इति चेदनुक्तत्वात्प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः । १४०२ अभि-
धानं पुनः स्वाभाविकम् । १४०३ एकादीनां दशादिभिर्द्वन्द्वः । १४०४ एकादीनां दशादिभिर्द्वन्द्व
इति चेद्विंशत्यादिषु वचनप्रसङ्गः । १४०५ सिद्धं त्वधिकान्ता संख्या संख्यया समानाधिकर-
णाधिकारेऽधिकलोपश्च ॥

२ । ३० उपसर्जनं पूर्वम् ६५४ ॥ १४०६ उपसर्जनस्य पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् ।
१४०७ न वानिष्टदर्शनात् । १४०८ षष्ठ्यन्तयोः समासेऽर्थाभेदात्प्रधानस्यापूर्वनिपातः ॥

२ । ३४ अल्पाच्तरम् ९०५ ॥ १४०९ अतन्त्रे तरनिर्देशे शङ्खतूणवयोर्मृदङ्गेन समासः ।
१४१० अनेकप्राप्तावेकस्य नियमोऽनियमः शेषेषु । १४११ ऋतुनक्षत्राणामानुपूर्व्येण समा-
नाक्षराणाम् । १४१२ अभ्यर्हितम् । १४१३ लघ्वक्षरम् । १४१४ सर्वत एवाभ्यर्हितं पूर्वं निप-
ततीति वाच्यम् । १४१५ वर्णानामानुपूर्व्येण । १४१६ भ्रातुश्च ज्यायसः । १४१७ संख्याया
अल्पीयस्याः । १४१८ धर्मादिषूभयम् ॥

२ । ३५ सप्तमीविशेषणे बहुव्रीहौ ८३८ ॥ १४१९ बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्या-
नम् । १४२० वा प्रियस्य । १४२१ सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् ॥

२ । ३६ निष्ठा ८९९ ॥ १४२२ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम् ।
१४२३ न वोत्तरपदस्यान्तोदात्तवचनं ज्ञापकं परभावस्य । १४२४ प्रतिषेधे तु पूर्वनिपातप्रस-
ङ्गस्तस्माद्राजदन्तादिषु पाठः । १४२५ प्रहरणार्थेभ्यश्च । १४२६ द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन ।
१४२७ उभाभ्यामल्पाच्तरम् ॥

२ । ३८ कडाराः कर्मधारये ७५१ ॥ १४२८ कडारादय इति वक्तव्यम् ॥

३ । १ अनभिहिते ५३६ ॥ १४२९ अनभिहितवचनमनर्थकमन्यत्रापि विहितस्याभावाद-
भिहिते । १४३० भस्त्वहुजकत्सु नानादेशत्वादुत्सर्गाप्रतिषेधः । १४३१ अनभिहितस्तु विभ-
क्त्यर्थस्तस्मादनभिहितवचनम् । १४३२ अभिहिते प्रथमाभावः । १४३३ तिङ्कृत्तद्धितसमासैः
परिसंख्यानम् । १४३४ उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् । १४३५
द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहिते विभक्त्यभावप्रसङ्गः । १४३६ न वान्यतरेणानभि-

धानात्। १४३७ अनभिहिते हि विधानम्। १४३८ अनभिहितवचनमनर्थकं प्रथमाविधानस्यानवकाशत्वात्। १४३९ अवकाशोऽकारकमिति चेन्नास्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति। १४४० विप्रतिषेधाद्वा प्रथमाभावः। १४४१ कृत्प्रयोगे तु परं विधानं षष्ठ्यास्तत्प्रतिषेधार्थम्॥

३।२ कर्मणि द्वितीया ५३७॥ १४४२ समयानिकषाहायोगेषूपसंख्यानम्। १४४३ द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषूपसंख्यानम्। १४४४ उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते॥

३।४ अन्तरान्तरेणयुक्ते ५४५॥ १४४५ अन्तरान्तरेणयुक्तानामप्रधानवचनम्॥

३।५ कालाध्वनोरत्यन्तसंयोगे ५५८॥ १४४६ अत्यन्तसंयोगे कर्मवद्भावार्थम्॥

३।६ अपवर्गे तृतीया ५६३॥ १४४७ क्रियापवर्ग इति वक्तव्यम्॥

३।७ सप्तमीपञ्चम्यौ कारकमध्ये ६४३॥ १४४८ क्रियामध्य इति वक्तव्यम्॥

३।८ कर्मप्रवचनीययुक्ते द्वितीया ५४८॥ १४४९ कर्मप्रवचनीययुक्ते प्रत्यादिभिश्च लक्षणादिषूपसंख्यानं सप्तमीपञ्चम्योः प्रतिषेधार्थम्॥

३।९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ६४२॥ १४५० यस्य चेश्वरवचनमिति कर्तृनिर्देशश्चेदवचनात्सिद्धम्। १४५१ प्रथमानुपपत्तिस्तु। १४५२ स्ववचनात्सिद्धम्॥

३।१२ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ५८५॥ १४५३ अध्वन्यर्थग्रहणम्। १४५४ आस्थितप्रतिषेधश्च। १४५५ चेष्टायामनध्वनि स्त्रियं गच्छत्यजां नयतीत्यतिप्रसङ्गः। १४५६ सिद्धं त्वसंप्राप्तवचनात्। १४५७ अध्वनश्चानपवादः॥

३।१३ चतुर्थी संप्रदाने ५७०॥ १४५८ चतुर्थीविधाने तादर्थ्य उपसंख्यानम्। १४५९ क्लृपि संपद्यमाने। १४६० उत्पातेन ज्ञाप्यमाने। १४६१ हितयोगे च॥

३।१६ नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ५८३॥ १४६२ स्वस्तियोगे चतुर्थी कुशलार्थैराशिषि वाविधानात्। १४६३ अलमिति पर्याप्त्यर्थग्रहणम्॥

३।१७ मन्यकर्मण्यनादरे विभाषाप्राणिषु ५८४॥ १४६४ यदेतदप्राणिष्वित्येतदनावादिष्विति वक्ष्यामि। १४६५ मन्यकर्मणि प्रकृष्टकुत्सितग्रहणम्॥

३।१८ कर्तृकरणयोस्तृतीया ५६१॥ १४६६ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम्॥

३।१९ सहयुक्तेऽप्रधाने ५६४॥ १४६७ सहयुक्तेऽप्रधानवचनमनर्थकमुपपदविभक्तेः कारकविभक्तिर्बलीयस्त्वादन्यत्रापि॥

३।२० येनाङ्गविकारः ५६५॥ १४६८ अङ्गाद्विकृतात्तद्विकारतश्चेदङ्गिनो वचनम्॥

३।२१ इत्थंभूतलक्षणे ५६६॥ १४६९ इत्थंभूतलक्षणे तत्स्थे प्रतिषेधः। १४७० नवेत्थंभूतस्य लक्षणेनापृथग्भावात्॥

३।२२ संज्ञोऽन्यतरस्यां कर्मणि ५६७॥ १४७१ संज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन। १४७२ उपपदविभक्तेश्चोपपदविभक्तिः॥

३।२३ हेतौ ५६८॥ १४७३ निमित्तकारणहेतुषु सर्वासां प्रायोदर्शनम्॥

३।२८ अपादाने पञ्चमी ५८७॥ १४७४ पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्या-

नम् । १४७५ अधिकरण च । १४७६ प्रभाख्यानयोश्च । १४७७ यतश्चाध्वकालनिर्माणम् । १४७८ तद्युक्तात्काले सप्तमी । १४७९ अध्वनः प्रथमा च ॥

३ । ३२ पृथग्विनानानाभिस्तृतीयान्यतरस्याम् ६०३ ॥ १४८० पृथगादिषु पञ्चमीविधानम् । १४८१ अनधिकारात् । १४८२ अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः ॥

३ । ३५ दूरान्तिकार्थेभ्यो द्वितीया च ६०५ ॥ १४८३ दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात्पञ्चमीप्रतिषेधः । १४८४ न वा तत्रापि दर्शनादप्रतिषेधः ॥

३ । ३६ सप्तम्यधिकरणे च ६३३ ॥ १४८५ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानम् । १४८६ साध्वसाधुप्रयोगे च । १४८७ कारकार्हाणां च कारकत्वे । १४८८ अकारकार्हाणां चाकारकत्वे । १४८९ तद्विपर्यासे च । १४९० निमित्तात्कर्मयोगे ॥

३ । ३७ यस्य च भावेन भावलक्षणम् ६३४ ॥ १४९१ भावलक्षणे सप्तमीविधानेऽभावलक्षण उपसंख्यानम् । १४९२ सिद्धं तु भावप्रवृत्तौ यस्य भावारम्भवचनात् ॥

३ । ४३ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ६४० ॥ १४९३ अप्रत्यादिभिरिति वक्तव्यम् ॥

३ । ४६ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ५३२ ॥ १४९४ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्य उपसंख्यानमधिकृतत्वात् । १४९५ न वा वाक्यार्थत्वात् । १४९६ अभिहितलक्षणायामनभिहिते प्रथमाविधिः । १४९७ अभिहितानभिहिते प्रथमाभावः । १४९८ तिङ्समानाधिकरण इति चेत्तिङोऽप्रयोगे प्रथमाविधिः । १४९९ शतृशानचोश्च निमित्तभावात्तिङोऽभावस्तयोरपवादत्वात् ॥

३ । ५० षष्ठी शेषे ६०६ ॥ १५०० प्रत्ययावधारणाच्छेषवचनम् । १५०१ अर्थावधारणाद्वा । १५०२ षष्ठी शेष इति चेद्विशेष्यस्य प्रतिषेधः । १५०३ तत्र प्रथमाविधिः ॥

३ । ५२ अधीगर्थदयेशां कर्मणि ६१३ ॥ १५०४ कर्मादिष्वकर्मकवद्वचनम् । १५०५ कर्माभिधाने लिङ्गवचनानुपपत्तिः । १५०६ षष्ठीप्रसङ्गश्च ॥

३ । ५४ रुजार्थानां भाववचनानामज्वरेः ६१५ ॥ १५०७ अज्वरिसंताप्योरिति वक्तव्यम् ॥

३ । ६१ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ६२१ ॥ १५०८ हविषोऽप्रस्थितस्य ॥

३ । ६२ चतुर्थ्यर्थे बहुलं छन्दसि ३३९६ ॥ १५०९ षष्ठ्यर्थे चतुर्थीवचनम् ॥

३ । ६५ कर्तृकर्मणोः कृति ६२३ ॥ १५१० कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यं लप्रतिषेधात् । १५११ तस्य कर्मकर्त्रर्थमिति चेन्नप्रतिषेधेऽपि तदन्तकर्मकर्तृत्वात्सिद्धम् ॥

३ । ६६ उभयप्राप्तौ कर्मणि ६२४ ॥ १५१२ उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधेऽकादिप्रयोगेऽप्रतिषेधः । १५१३ अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यम्, शेषे विभाषा ॥

३ । ६७ क्तस्य च वर्तमाने ६२५ ॥ १५१४ क्तस्य च वर्तमाने नपुंसके भाव उपसंख्यानम् । १५१५ शेषविज्ञानात्सिद्धम् ॥

३ । ६९ न लोकाव्ययनिष्ठाखलर्थतृनाम् ६२७ ॥ १५१६ लादेशे सद्ग्रहणं किकिनोः प्रतिषेधार्थम् । १५१७ तयोरलादेशत्वात् । १५१८ उकारप्रयोगे नेति वक्तव्यम् । १५१९ उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः । १५२० अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः । १५२१ शानंश्चानश्शतृणामुपसंख्यानम् । १५२२ द्विषः शतुर्वावचनम् ॥

३ । ७० अकेनोर्भविष्यदाधमर्ण्ययोः ६२८ ॥ १५२३ अकस्य भविष्यति । १५२४ इन आधमर्ण्ये च ॥

३ । ७१ कृत्यानां कर्तरि वा ६२९ ॥ १५२५ भव्यादीनां कर्मणोऽनभिधानात्कृत्यानां कर्तृग्रहणम् ॥

४ । १ द्विगुरेकवचनम् ७३१ ॥ १५२६ प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानम् । १५२७ तत्रानुप्रयोगस्यैकवचनाभावोऽद्विगुत्वात् । १५२८ सिद्धं तु द्विग्वर्थस्यैकवद्वचनात् । १५२९ एकशेषप्रतिषेधश्च । १५३० न वान्यस्यानेकत्वात् । १५३१ समाहारग्रहणं च तद्धितार्थप्रतिषेधार्थम् । १५३२ न वा समाहारैकत्वात् ॥

४ । २ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ९०६ ॥ १५३३ प्राणितूर्यसेनाङ्गानां तत्पूर्वपदोत्तरपदग्रहणम् । १५३४ योगविभागात्सिद्धम् ॥

४ । ३ अनुवादे चरणानाम् ९०७ ॥ १५३५ स्थेणोः । १५३६ अद्यतन्यां च ॥

४ । ७ विशिष्टलिङ्गो नदी देशोऽग्रामाः ९११ ॥ १५३७ ग्रामप्रतिषेधे नगरप्रतिषेधः । १५३८ उभयतश्च ग्रामाणाम् ॥

४ । ११ गवाश्वप्रभृतीनि च ९१५ ॥ १५३९ गवाश्वप्रभृतिषु यथोच्चरितं द्वन्द्ववृत्तम् ॥

४ । १२ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ९१६ ॥ १५४० बहुप्रकृतिः फलसेनावनस्पतिमृगशकुन्तक्षुद्रजन्तुधान्यतृणानाम् । १५४१ पशुशकुनिद्वन्द्वे विरोधिनां पूर्वविप्रतिषिद्धम् । १५४२ अश्ववडवयोः पूर्वलिङ्गत्वात्पशुद्वन्द्वनपुंसकम् । १५४३ प्रातिपदविधानात्सिद्धम् । १५४४ एकवचनमनर्थकं समाहारैकत्वात् ॥

४ । २६ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ८१२ ॥ १५४५ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति चेत्प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः । १५४६ पूर्वपदस्य च । १५४७ समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनम् । १५४८ निपातनात्सिद्धम् । १५४९ उपसर्जनह्रस्वत्वं वा । १५५० परवल्लिङ्गमिति शब्दशब्दार्थौ १५५१ प्राप्तादिषु चैकदेशिग्रहणात्सिद्धम् ॥

४ । २९ रात्राह्नाहाः पुंसि ८१४ ॥ १५५२ अनुवाकादयः पुंसि ॥

४ । ३० अपथं नपुंसकम् ८१५ ॥ १५५३ पुण्यसुदिनाभ्यामह्नो नपुंसकत्वं वक्तव्यम् । १५५४ पथः संख्याव्ययादेः । १५५५ द्विगुश्च । १५५६ अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यत इति वक्तव्यम् । १५५७ वाबन्तः । १५५८ अनो नलोपश्च वा च स्त्रियां भाष्यत इति वक्तव्यम् । १५५९ पात्रादिभ्यः प्रतिषेधो वक्तव्यः ॥

४ । ३१ अर्धर्चाः पुंसि च ८१६ ॥ १५६० अर्धर्चादय इति वक्तव्यम् ॥

४ । ३२ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ३५० ॥ १५६१ अन्वादेशे समानाधिकरणग्रहणम् । १५६२ देवदत्तं भोजयेमं चेत्यप्रसङ्गार्थम् । १५६३ अन्वादेशश्च कथितानुकथनमात्रम् । १५६४ आदेशवचनं साकच्कार्थम् । १५६५ शित्करणं सर्वादेशार्थम् । १५६६ न वान्त्यस्य विकारवचनानर्थक्यात् । १५६७ अर्थवत्त्वादेशप्रतिषेधार्थम् । १५६८ तस्माच्छित्करणम् ॥

४ । ३४ द्वितीयाटौस्स्वेनः ३५१ ॥ १५६९ एनदिति नपुंसकैकवचने ॥

४ । ३५ आर्धधातुके २४३२ ॥ १५७० जग्ध्यादिष्वार्धधातुकाश्रयत्वात्साति तस्मिन्नि-

धानम् । १५७१ तत्रोत्सर्गलक्षणप्रतिषेधः । १५७२ सामान्याश्रयत्वाद्विशेषस्यानाश्रयः । १५७३ सामान्याश्रयत्वाद्विशेषस्यानाश्रय इति चेदवर्णाकारान्तेभ्यो ण्यद्विधिप्रसङ्गः । १५७४ पौर्वापर्याभावाच्च सामान्येनानुपपत्तिः । १५७५ सिद्धं तु सार्वधातुके प्रतिषेधात् ॥

४ । ३७ लुङ्सनोर्घस्लृ २४२७ ॥ १५७६ घस्लृभावेऽच्युपसंख्यानम् ॥

४ । ४५ इणो गा लुङि २४५८ ॥ १५७७ इण्वदिकः ॥

४ । ४९ गाङ् लिटि २४५९ ॥ १५७८ गाङ्यनुबन्धकरणं विशेषणार्थम् । १५७९ ज्ञापकं वा सानुबन्धकस्यादेशवचन इत्कार्याभावस्य । १५८० प्रयोजनं चक्षिङः ख्याञ् । १५८१ लटः शतृशानचौ । १५८२ युवोरनाकौ । १५८३ मेश्चानुबन्धकस्याम्वचनम् ॥

४ । ५४ चक्षिङः ख्याञ् २४३६ ॥ १५८४ चक्षिङः क्शाञ्ख्याञौ । १५८५ ख्शादिर्वा । १५८६ असिद्धे शस्य यवचनं विभाषा । १५८७ प्रयोजनं सौप्रख्ये वुञ्विधिः । १५८८ निष्ठानत्वमाख्याते । १५८९ रुविधिः पुंख्याने । १५९० णत्वं पर्याख्याने । १५९१ सस्थानत्वं नमःख्यात्रे । १५९२ वर्जने प्रतिषेधः । १५९३ असनयोश्च । १५९४ बहुलं तणि । १५९५ अन्नवधकगात्रविचक्षणाजिराद्यर्थम् ॥

४ । ५६ अजेर्व्यघञपोः २२९२ ॥ १५९६ घञपोः प्रतिषेधे क्यप उपसंख्यानम् । १५९७ ('वलादावार्धधातुके वेष्यते' इति काशिका भाष्यसंमता) ॥

४ । ५८ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः १२७६ ॥ १५९८ अणिञोर्लुकि तद्राजाद्युवप्रत्ययस्योपसंख्यानम् । १५९९ अणिञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् । १६०० अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम् ॥

४ । ६२ तद्राजस्य बहुषु तेनैवास्त्रियाम् ११९३ ॥ १६०१ तद्राजादीनां लुकि समासबहुत्वे प्रतिषेधः । १६०२ अबहुत्वे च लुग्वचनम् । १६०३ द्वन्द्वेऽबहुषु लुग्वचनम् । १६०४ सिद्धं तु प्रत्ययार्थबहुत्वे लुग्वचनात् । १६०५ द्वन्द्वेऽबहुषु लुग्वचनम् । १६०६ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक् । १६०७ एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि । १६०८ न वा सर्वेषां द्वन्द्वे बह्वर्थत्वात् ॥

४ । ६४ यञञोश्च ११०८ ॥ १६०९ यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम् ॥

४ । ६७ न गोपवनादिभ्यः ११४९ ॥ १६१० गोपवनादिप्रतिषेधः प्राग्घरितादिभ्यः ॥

४ । ६९ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ११५१ ॥ १६११ अद्वन्द्व इति द्वन्द्वाधिकारनिवृत्त्यर्थम् ॥

४ । ७० आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ११५२ ॥ १६१२ आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् । १६१३ लुक्प्रतिषेधे वृद्ध्यर्थम् । १६१४ प्रत्ययान्तनिपातने हि वृद्ध्यभावः । १६१५ अधिकारात्प्रत्ययलोपः ॥

४ । ७४ यङोऽचि च २६५० ॥ १६१६ ऊतोऽचि ॥

४ । ७७ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु २२२३ ॥ १६१७ गापोर्ग्रहण इण्पिबत्योर्ग्रहणम् ॥

४ । ७९ तनादिभ्यस्तथासोः २५४७ ॥ १६१८ तथासोरात्मनेपदवचनम् । १६१९ एकवचनग्रहणं वा । १६२० अवचने ह्यनिष्टप्रसङ्गः ॥

४ । ८१ आमः २२३८ ॥ १६२१ आमो लेर्लोपे लुङ्लोटोरुपसंख्यानम् । १६२२ आमन्तेभ्यो णलः प्रतिषेधः । १६२३ आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेधः । १६२४ आमन्तेभ्योऽर्थवद्ग्रहणाण्णलोऽप्रतिषेध इति चेदमः प्रतिषेधः । १६२५ लुगादेशापवादः । १६२६ तिङ्कृताभावस्तु । १६२७ सुबन्तपदत्वात्सिद्धम् । १६२८ लकारस्य कृत्त्वात्प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम् । १६२९ अव्ययत्वं मकारान्तत्वात् । १६३० स्वरः कृदन्तप्रकृतिस्वरत्वात् । १६३१ तथा च निघातानिघातसिद्धिः । १६३२ नञा तु समासप्रसङ्गः ॥

४ । ८२ अव्ययादाप्सुपः ४७२ ॥ १६३३ अव्ययादाप्यो लुग्वचनानर्थक्यं लिङ्गाभावात् ॥

४ । ८३ नाव्ययीभावादतोऽम्त्वपञ्चम्याः ६५७ ॥ १६३४ नाव्ययीभावादत इति योगव्यवसानम् । १६३५ पञ्चम्या अम्प्रतिषेधार्थम् । १६३६ एकयोगे ह्युभयोः प्रतिषेधः । १६३७ तुर्नियामकः । १६३८ अमि पञ्चमीप्रतिषेधेऽपादानग्रहणम् । १६३९ कर्मप्रवचनीययुक्तेऽप्रतिषेधार्थम् । १६४० न वोत्तरपदस्य कर्मप्रवचनीययोगात्समासात्पञ्चम्यभावः ॥

४ । ८४ तृतीयासप्तम्योर्बहुलम् ६६५८ ॥ १६४१ सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यम् ॥

४ । ८५ लुटः प्रथमस्य डारौरसः २१८८ ॥ १६४२ टितां टेरेविधेर्लुटो डारौरसः पूर्वविप्रतिषिद्धम् । १६४३ आत्मनेपदानां चेति वचनात्सिद्धम् । १६४४ तत्र समसंख्यार्थम् । १६४५ डाविकारस्य शित्करणं सर्वादेशार्थम् । १६४६ निघातप्रसङ्गस्तु । १६४७ सिद्धमलोऽन्त्यविकारात् । १६४८ डिति टेर्लोपाल्लोपः । १६४९ अनित्त्वाद्वा । १६५० प्रश्लिष्टनिर्देशाद्वा । १६५१ तिङ्ग्रहणमेकदेशविकृतस्यानन्यत्वात् । १६५२ स्वरे विप्रतिषेधात्सिद्धम् ॥

इति द्वितीयोऽध्यायः ।

तृतीयोऽध्यायः ।

१ । १ प्रत्ययः १८० ॥ १६५३ प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनामप्रतिषेधः । १६५४ निमित्तस्य निमित्तिकार्यार्थत्वादन्यत्रापि । १६५५ प्रधाने कार्यसंप्रत्ययाद्वा सिद्धम् । १६५६ विकारागमेषु च परविज्ञानात् । १६५७ षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात् । १६५८ प्रत्ययविधानानुपपत्तिस्तु । १६५९ तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धम् । १६६० अर्थाश्रयत्वाद्वा ॥

१ । २ परश्च १८१ ॥ १६६१ परवचनमनर्थकं पञ्चमीनिर्दिष्टाद्धि परस्य । १६६२ अत्यन्तापरदृष्टानां वा परभूतलोपार्थम् । १६६३ प्रयोगनियमार्थं वा । १६६४ प्रकृतेरर्थाभिधाने प्रत्ययादर्शनात् । १६६५ ङ्यसजादीनां च केवलदृष्टत्वात् । १६६६ वावचने चानुत्पत्त्यर्थम् । १६६७ तत्र प्रत्ययनियमे प्रकृतिनियमाभावः । १६६८ प्रकृतिनियमे प्रत्ययानियमः । १६६९ सिद्धं तूभयनियमात् ॥

१ । ३ आद्युदात्तश्च ३७०८ ॥ १६७० आद्युदात्तत्वस्य प्रत्ययसंज्ञासंनियोगे प्रयोजनं यस्य संज्ञाकरणं तस्याद्युदात्तार्थम् । १६७१ असंनियोगे हि यस्मात्स तदादेराद्युदात्तत्वं तदन्तस्य चानुदात्तत्वम् । १६७२ न वा प्रकृतेराद्युदात्तवचनं ज्ञापकं तदादेरग्रहणस्य । १६७३ प्रकृतिस्वरस्य विधानसामर्थ्यात्प्रत्ययस्वराभावः । १६७४ आगमानुदात्तार्थं वा । १६७५ न वागमस्यानुदात्तवचनात् । १६७६ अवचने हि सीयुडादेराद्युदात्तत्वम् । १६७७ आद्यु-

दात्तस्य वा लोपार्थम् । १६७८ न वा बहिरङ्गलक्षणत्वात् । १६७९ अवचने हिम्नित्क्त्स्वतिप्रसङ्गः । १६८० प्रत्ययाद्युदात्तत्वाद्धातोरन्तः । १६८१ पित्स्वरात्तित्स्वरश्चापि । १६८२ चित्स्वरश्चापि पित्स्वरात् । १६८३ न वाद्युदात्तस्य प्रत्ययसंज्ञासंनियोगात् । १६८४ टापि स्वरितेनैकादेशः । १६८५ चापि चित्करणात् ॥

१ । ५ गुप्तिज्किद्भ्यः सन् २३९३ ॥ १६८६ गुपादिष्वनुबन्धकरणमात्मनेपदार्थम् । ('१६८७ गुपेर्निन्दायाम् । १६८८ तिजेः क्षमायाम् । १६८९ कितेर्व्याधिप्रतीकारे' इति कौशिकार्थः) ॥

१ । ६ मान्बधदानशान्भ्यो दीर्घश्चाभ्यासस्य २३९४ ॥ १६९० अभ्यासदीर्घत्वेऽवर्णस्य दीर्घप्रसङ्गः । १६९१ न वाभ्यासविकारेष्वपवादस्योत्सर्गाबाधकत्वात् । ('१६९२ मानेर्जिज्ञासायाम् । १६९३ बधेर्वैरूप्ये । १६९४ दानेरार्जवे । १६९५ शानेर्निशाने' इति कौशिका) ॥

१ । ७ धातोः कर्मणः समानकर्तृकादिच्छायां वा २६०८ ॥ १६९६ कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यम् । १६९७ सोपसर्गे वै कर्म । १६९८ सोपसर्गं कर्मेति चेत्कर्मविशेषकत्वादुपसर्गस्यानुपसर्गं कर्म । १६९९ सोपसर्गस्य हि कर्मत्वे धात्वधिकारेऽपि सनोऽविधानमकर्मकत्वात् । १७०० सुबन्ताच्चाप्रसङ्गः क्यजादीनामपवादत्वात् । १७०१ अनभिधानाद्वा । १७०२ कर्मसमानकर्तृकग्रहणानर्थक्यं चेच्छाभिधाने प्रत्ययविधानात् । १७०३ अकर्मणो ह्यसमानकर्तृकाद्वानभिधानम् । १७०४ अङ्गपरिमाणार्थं तु । १७०५ वावचनानर्थक्यं च तत्र नित्यत्वात्सनः । १७०६ तुमुन्ताद्वा तस्य च लुग्वचनम् । १७०७ आशङ्कायामचेतनेषूपसंख्यानम् । १७०८ न वा तुल्यकारणत्वादिच्छाया हि प्रवृत्तित उपलब्धिः । १७०९ उपमानाद्वा सिद्धम् । १७१० सर्वस्य वा चेतनावत्त्वात् ॥

१ । ८ सुप आत्मनः क्यच् २६५७ ॥ १७११ छन्दस्यघशब्दात्परेच्छायां क्यज् । १७१२ समानाधिकरणानां सर्वत्रावृत्तिरयोगादेकेन । १७१३ द्वितीयानुपपत्तिस्तु । १७१४ क्यचि मान्ताव्ययप्रतिषेधः । १७१५ गोसमानाक्षरनान्तादित्येके ॥

१ । ९ काम्यच्च २६६३ ॥ १७१६ काम्यचश्चित्करणानर्थक्यं कस्येदर्थाभावात् ॥

१ । १० उपमानादाचारे २६६४ ॥ १७१७ अधिकरणाच्च ॥

१ । ११ कर्तुः क्यङ् सलोपश्च २६६५ ॥ १७१८ सलोपो वा । १७१९ ओजोऽप्सरसोर्नित्यम् । १७२० सलोपोऽप्सरस एव । १७२१ आचारे गल्भक्लीबहोडेभ्यः क्विब्वा । १७२२ सर्वप्रातिपदिकेभ्य आचारे क्विब्वक्तव्योऽश्वति गर्दभतीत्येवमर्थम् ॥

१ । १२ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः २६६७ ॥ १७२३ भृशादिष्वभूततद्भावग्रहणम् । १७२४ च्विप्रतिषेधानर्थक्यं च भवत्यर्थे क्यङ्वचनात् । १७२५ भवतियोगे च्विविधानम् । १७२६ डाचि वचनप्रामाण्यात् । १७२७ भृशादिषूपसर्गः प्रत्ययार्थविशेषणमिति चेत्स्वरे दोषः । १७२८ सोपसर्गादिति चेदडुत्यद्विर्वचनेषु दोषः ॥

१ । १३ लोहितादिडाज्भ्यः क्यष् २६६८ ॥ १७२९ लोहितडाज्भ्यः क्यष्वचनम् । १७३० भृशादिष्वितराणि ॥

१-२ गोपनाद्यर्थकानां धातूनामनेकार्थत्वान्निन्दादौ वृत्तिः—इति न्यायसिद्धानि न तु वाचनिकानि । अतएव भाष्ये न दृश्यन्ते ।

१ । १४ कष्टाय क्रमणे २६७० ॥ १७३१ सत्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् ॥

१ । १५ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः २६७१ ॥ १७३२ हनु चलने इति वक्तव्यम् । १७३३ तपसः परस्मैपदं च ॥

१ । १६ बाष्पोष्मभ्यामुद्वमने २६७२ ॥ १७३४ फेनाच्चेति वक्तव्यम् ॥

१ । १७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे २६७३ ॥ १७३५ अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणम् । १७३६ सुदिनदुर्दिनाभ्यां च । १७३७ नीहाराच्च ॥

१ । १९ नमोवरिवश्चित्रङः क्यच् २६७५ ॥ १७३८ नमसः क्यचि द्वितीयानुपपत्तिः । १७३९ प्रकृत्यन्तरत्वात्सिद्धम् । १७४० क्यजादिषु प्रत्ययार्थनिर्देशः । ('१७४१ नमसः पूजायाम् । १७४२ वरिवसः परिचर्यायाम् । १७४३ चित्रङ आश्चर्ये । १७४४ भाण्डात्समाचयने । १७४५ चीवरादर्जने परिधाने वा । १७४६ पुच्छादुदसने व्यसने पर्यसने च' इति वार्तिकव्याख्यानभाष्यम्) ॥

१ । २१ मुण्डमिश्रश्लक्ष्णलवणव्रतहलकलकृततूस्तेभ्यो णिच् २६७७ ॥ १७४७ हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थम् ॥

१ । २२ धातोरेकाचो हलादेः क्रियासमभिहारे यङ् २६२९ ॥ १७४८ यङ्विधौ धातुग्रहण उक्तम् (वा १६९६-१६९९) । १७४९ एकाज्झलादिग्रहणे च (वा १७०२-३)। १७५० ऊर्णोतेश्चोपसंख्यानम् । १७५१ सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णुग्रहणं यङ्विधावनेकाजहलाद्यर्थम् । १७५२ वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात् ॥ १७५३ क्रियासमभिहारे यङो विप्रतिषेधेन लोड्विधानम् । १७५४ न वा नानार्थत्वात्कर्तृकर्मणोर्हि लविधानं क्रियाविशेषे स्वार्थे यङ् । १७५५ उत्तरयोर्विग्रहेण विशेषासंप्रत्ययान्नित्यग्रहणानर्थक्यम् । १७५६ क्रियासमभिहारे च नेतेभ्यः ॥

१ । २५ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् २५६३ ॥ १७५७ सत्यस्य कृञ्यापुक्च । १७५८ णिविधावर्थवेदसत्यानामापुक्च ॥

१ । २६ हेतुमति च २५७६ ॥ १७५९ हेतुमतीति कारकोपादानं प्रत्ययार्थपरिग्रहार्थं यथा तनूकरणे तक्षः । १७६० हेतुनिर्देशश्च निमित्तमात्रं भिक्षादिषु दर्शनात् । १७६१ कृष्यादिषु चानुपपत्तिः । १७६२ कृष्यादिषु चानुपपत्तिर्नानाक्रियाणां कृष्यर्थत्वात् । १७६३ यज्यादिषु चाविपर्यासः । १७६४ यज्यादिषु चाविपर्यासो नानाक्रियाणां यज्यर्थत्वात् । १७६५ तत्करोतीत्युपसंख्यानं सूत्रयत्याद्यर्थम् । १७६६ आख्यानात्कृतस्तदाचष्ट इति कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् । १७६७ आख्यानाच्च प्रतिषेधः । १७६८ दृश्यर्थायां च प्रवृत्तौ । १७६९ आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम् । १७७० चित्रीकरणे प्रापि । १७७१ नक्षत्रयोगे ज्ञि । १७७२ न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम् । १७७३ स्वतन्त्रप्रयोजकत्वादप्रयोजक इति चेन्मुक्तसंशयेन तुल्यम् । १७७४ प्रवृत्तिर्ह्युभयत्रानपेक्ष्य । १७७५ कुर्वतः प्रयोजक इति चेत्तुल्यम् ॥

१ । २७ कण्ड्वादिभ्यो यक् २६७८ ॥ १७७६ कण्ड्वादिभ्यो वावचनम् । १७७७ अवचने हि नित्यप्रत्ययत्वम् । १७७८ तत्र धातुविधितुक्प्रतिषेधः । १७७९ ह्रस्वयलोपौ च ॥

१ । ३० कर्मणिङ् २३१० ॥ १७८० णिङि णित्करणस्य सावकाशत्वाद्वृद्धिप्रतिषेध-प्रसङ्गः । १७८१ मित्प्रतिषेधस्य चार्थवत्त्वात् ॥

१ । ३१ आयादय आर्धधातुके २३०५ ॥ १७८२ आयादिभ्यो यदार्धधातुकमायादि-प्रकृतेर्यदार्धधातुकमिति चोभयथानिष्टप्रसङ्गः । १७८३ सिद्धं तु सार्वधातुके नित्यवचनाद-नाश्रित्य वाविधानम् । १७८४ स्यादिबलीयस्त्वं तु विप्रतिषेधेन तुल्यनिमित्तत्वात् । १७८५ न वायादिविधानस्यानवकाशत्वात् ॥

१ । ३३ स्यतासी ऌलुटोः २१८६ ॥ १७८६ अपवादविप्रतिषेधाच्छ्वादिबाधनम् ॥ १७८७ अपवादो नामानेकलक्षणप्रसङ्गः । १७८८ अपवादविप्रतिषेधाच्छ्वचनादिबाधनम् ॥

१ । ३४ सिब्बहुलं लेटि ३४२५ ॥ १७८९ सिब्वुत्सर्गश्छन्दसि । १७९० सनाद्यन्ते नेयत्त्वाद्यर्थः । १७९१ प्रकृत्यन्तरत्वात्सिद्धम् । १७९२ पित्करणानर्थक्यं चानक्त्वात् । १७९३ इटोऽनुदात्तार्थमिति चेदागमानुदात्तत्वात्सिद्धम् । १७९४ सिब्बहुलं छन्दसि णित् ॥

१ । ३५ कास्प्रत्ययादाममन्त्रे लिटि २३०६ ॥ १७९५ कास्ग्रहणे चकास उपसंख्या-नम् । १७९६ कास्यनेकाच इति वक्तव्यम् ॥

१ । ३६ इजादेश्च गुरुमतोऽनृच्छः २२३७ ॥ १७९७ गुरुमत आम्विधाने लिण्निमि-त्तात्प्रतिषेधः । १७९८ गुरुमद्वचनं किमर्थमिति चेण्णमुल्युत्तमे यजादिप्रतिषेधार्थम् । १७९९ उपदेशवचनात्सिद्धम् । १८०० उच्छेराम्वक्तव्यः । १८०१ ऋच्छिप्रतिषेधो ज्ञापक उच्छेरा-म्भावस्य । १८०२ ऊर्णोतेश्चोपसंख्यानम् ॥

१ । ३८ उषविदजागृभ्योऽन्यतरस्याम् २३४१ ॥ १८०३ विदेराम्कित् । ('१८०४ निपातनाद्वागुणत्वम्' इति भारद्वाजीयपाठः) ॥

१ । ३९ भीह्रीभृहुवां श्लुवच्च २४९१ ॥ १८०५ श्लुवदतिदेशे प्रयोजनं द्वित्वेत्वे ॥

१ । ४० कृञ्चानुप्रयुज्यते लिटि २२३९ ॥ १८०६ कृञोऽनुप्रयोगवचनमस्तिभूप्रतिषेधा-र्थम् । १८०७ आत्मनेपदविध्यर्थं च । १८०८ इष्टः सर्वानुप्रयोगः । १८०९ सर्वानुप्रयोग इति चेदाशिष्यमर्थाभावात् । १८१० अर्थाभावाचान्यस्य । १८११ लिट्परार्थं वा । १८१२ अर्थस-मानेर्वानुप्रयोगो न स्यात् । १८१३ विपर्यासनिवृत्त्यर्थं वा । १८१४ व्यवहितनिवृत्त्यर्थं च ॥

१ । ४३ च्लि लुङि २२२१ ॥ १८१५ च्ल्युत्सर्गः सामान्यग्रहणार्थः । १८१६ क्सवि-धाने चानिड्वचने च्लिसंप्रत्ययार्थः । १८१७ घस्लभावे च । १८१८ च्लेश्चित्करणं विशेषणा-र्थम् । १८१९ इदित्करणं सामान्यग्रहणार्थम् ॥

१ । ४४ च्लेः सिच् २२२२ ॥ १८२० सिचश्चित्करणानर्थक्यं स्थानिवत्त्वात् । १८२१ अर्थवत्तु चित्करणसामर्थ्याद्धीट उदात्तत्वम् । १८२२ तस्माच्चित्करणम् । १८२३ इदि-त्करणं नकारलोपाभावार्थम् । १८२४ न वा हन्तेः सिचः कित्करणं ज्ञापकं नकारलोपाभा-वस्य । १८२५ इदित्त्वाद्वा स्थानिवत्त्वात् । १८२६ स्पृशमृशकृषतृपदृपः सिज्वा । १८२७ सिद्धं तु सिचो यादित्वात् । १८२८ चङङोः प्रश्लिष्टनिर्देशात्सिद्धम् । १८२९ चिणोऽनित्त्वात् ॥

१ । ४५ शल इगुपधादनिटः क्सः २३३६ ॥ १८३० क्सविधान इगुपधाभावश्च्लेर्गुणनि-मित्तत्वात् । १८३१ न वा क्सस्यानवकाशत्वादपवादो गुणस्य । १८३२ अनिड्वचनमविशेषणं

च्लेर्नित्यादिष्टत्वात् । १८३३ न वा क्सस्य सिजपवादत्वात्तस्य चानिडाश्रयत्वादनिटि प्रसिद्धे क्सविधिः । १८३४ शेषे सिज्विधानम् ॥

१ । ४६ श्लिष आलिङ्गने २५१४ ॥ १८३५ श्लिष आलिङ्गने नियमानुपपत्तिर्विधेयभावात् । १८३६ सिद्धं तु श्लिष आलिङ्गनेऽच्चिण्विषये । १८३७ अङ्विधाने च श्लिषोऽनालिङ्गने । १८३८ योगविभागात्सिद्धम् ॥

१ । ४८ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् २३१२ ॥ १८३९ णिश्रिद्रुस्रुषु कर्मरुपसंख्यानम् । १८४० कर्मकर्तरि च । १८४० न वा कर्मण्यविधानात्कर्तृत्वाच्च कर्मकर्तुः सिद्धम् ॥

१ । ५२ अस्यतिवक्तिख्यातिभ्योऽङ् २४३८ ॥ १८४१ अस्यतिग्रहणमात्मनेपदार्थम् । १८४२ पुषादित्वात् । १८४३ कर्मकर्तरि च ॥

१ । ६७ सार्वधातुके यक् २७५६ ॥ १८४४ भावकर्मकर्तारः सार्वधातुकार्थाश्चेदेकादिबहुषु नियमानुपपत्तिरतदर्थत्वात् । १८४५ विकरणार्थां इति चेत्कृनाभिहिते विकरणाभावः । १८४६ भावकर्मणोर्यग्विधाने कर्मकर्तर्युपसंख्यानम् । १८४७ विप्रतिषेधाद्धि शपो बलीयस्त्वम् । १८४८ योगविभागात्सिद्धम् ॥

१ । ७८ रुधादिभ्यः श्नम् २५४३ ॥ १८४९ श्नमि शित्करणं ङ्वादिहस्वार्थम् । १८५० न वा धात्वन्यत्वात् । १८५१ बहुलं पित्सार्वधातुकं छन्दसि ॥

१ । ८३ हलः श्नः शानज्झौ २५५७ ॥ १८५२ आविकारस्य शित्करणानर्थक्यं स्थानिवत्त्वात् । १८५३ अर्थवत्तु ज्ञापकं सार्वधातुकादेशेऽनुबन्धास्थानिवत्त्वस्य । १८५४ प्रयोजनं हितातङोरपित्त्वम् । १८५५ तबादिषु त्वाङित्त्वम् । १८५६ तस्य दोषो मिप आदेशे पिद्भावः । १८५७ विदेर्वसोः शित्त्वम् । १८५८ कित्करणाद्वा सिद्धम् ॥

१ । ८४ छन्दसि शायजपि ३४३२ ॥ १८५९ शायच्छन्दसि सर्वत्र ॥

१ । ८६ लिङ्याशिष्यङ् ३४३४ ॥ १८६० आशिष्यङः प्रयोजनं स्थागागमिवचिविदयः । १८६१ शकिरुहोश्चेति वक्तव्यम् । १८६२ दृशेरक् पितरं दृशेयं मातरं च ॥

१ । ८७ कर्मवत्कर्मणा तुल्यक्रियः २७६६ ॥ १८६३ कर्मवदकर्मकस्य कर्ता । १८६४ कर्म दृष्टश्चेत्समानधातौ । १८६५ कर्मस्थभावकानां कर्मस्थक्रियाणां च । १८६६ आत्मनेपदशबादिविधिप्रतिषेधः । १८६७ कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितत्वात् । १८६८ तत्र लान्तस्य कर्मवदनुदेशः । १८६९ इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेधः । १८७० सिद्धं तु प्राकृतकर्मत्वात् । १८७१ आत्मसंयोगे कर्मकर्तुः कर्मदर्शनात् । १८७२ पदलोपश्च । १८७३ सकर्मकाणां प्रतिषेधोऽन्योन्यमाश्लिष्यत इति । १८७४ तपेर्वा सकर्मकस्य वचनं नियमार्थम् । १८७५ तस्य च तपःकर्मकस्यैव । १८७६ दुहिपच्योर्बहुलं सकर्मकयोः । १८७७ सृजियुज्योः श्यस्तु । १८७८ करणेन तुल्यक्रियः कर्ता बहुलम् । १८७९ स्त्रक्न्यादीनां प्रतिषेधः । १८८० भूषाकर्मकिरतिसनां चान्यत्रात्मनेपदात् ॥

१ । ८९ न दुहस्नुनमां यक्चिणौ २७६७ ॥ १८८१ ॥ यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञामुपसंख्यानम् । १८८२ 'यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम्' इति भारद्वाजीयपाठः ॥

१ । ९० कुषिरजोः प्राचां श्यन्परस्मैपदं च २७७२ ॥ १८८३ कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् । १८८४ अवचने हि लिङ्लिटोः प्रतिषेधः ॥

१ । ९१ धातोः २८२९ ॥ १८८५ धात्वधिकारः प्राग्लादेशात् । १८८६ लादेशे हि व्यवहितत्वादप्रसिद्धिः । १८८७ आद्ये योगे न व्यवाये तिङः स्युः । १८८८ न स्यादेत्त्वं टेटितां यद्विधत्ते । १८८९ एशः शित्वम् । १८९० यच्च लोटो विधत्ते । १८९१ यच्चाप्युक्तं लिङ्लिटोस्तच्च न स्यात् ॥ १८९२ प्रयोजनं प्रातिपदिकप्रतिषेधः । १८९३ स्वपादिषु । १८९४ अङ्गसंज्ञा च । १८९५ कृत्संज्ञा च । १८९६ उपपदसंज्ञा च । १८९७ धातुग्रहणमनर्थकं यद्विधौ धात्वधिकारात् । १८९८ अनधिकारे ह्यङ्गसंज्ञाभावः । १८९९ हेतुमद्वचनं तु ज्ञापकमन्यत्राभावस्य । १९०० कण्ड्वादिषु च व्यपदेशिवद्वचनात्सिद्धम् ॥

१ । ९२ तत्रोपपदं सप्तमीस्थम् ७८१ ॥ १९०१ तत्रग्रहणं विषयार्थम् । १९०२ उपपदसंज्ञायां समर्थवचनम् । १९०३ निमित्तोपादानं च । १९०४ अनुपादाने ह्यनुपपदे प्रत्ययप्रसङ्गः । १९०५ निर्देशः संज्ञाकरणार्थः । १९०६ तत्रवचनमुपपदसंनियोगार्थम् ॥

१ । ९४ वासरूपोऽस्त्रियाम् २८३० ॥ १९०७ असरूपस्य वावचनमुत्सर्गस्य बाधकविषयेऽनिवृत्त्यर्थम् । १९०८ तत्रोत्पत्तिवाप्रसङ्गो यथा तद्धिते । १९०९ सिद्धं त्वसरूपस्य बाधकस्य वावचनात् । १९१० अनुबन्धभिन्नेषु विभाषाप्रसङ्गः । १९११ सिद्धमनुबन्धस्यानेकान्तत्वात् । १९१२ प्रयोगे चेल्लादेशेषु प्रतिषेधः । १९१३ स्त्रियां प्रतिषेधे क्त्ल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः । १९१४ स्त्रियाः प्रागिति चेत्क्त्वायां वावचनम् । १९१५ कालादिषु तुमुनि । १९१६ अर्हे तृज्विधानम् ॥

१ । ९५ कृत्याः २८३१ ॥ १९१७ कृत्यसंज्ञायां प्राङ्ण्वुल्वचनम् । १९१८ अर्हे कृत्यतृज्वचनं तु ज्ञापकं प्राङ्ण्वुल्वचनानर्थक्यस्य ॥

१ । ९६ तव्यत्तव्यानीयरः २८३४ ॥ १९१९ केलिमर उपसंख्यानम् । १९२० वसेस्तव्यत्कर्तरि णिच्च । १९२१ तद्धितो वा ॥

१ । ९७ अचो यत् २८४२ ॥ १९२२ तकिशसिचतियतिजनीनामुपसंख्यानम् । १९२३ हनो वा वध च । १९२४ तद्धितो वा ॥

१ । १०० गदमदचरयमश्चानुपसर्गे २८४८ ॥ १९२५ अनुपसर्गाच्चरेराङि चागुरौ ॥

१ । १०३ अर्यः स्वामिवैश्ययोः २८५१ ॥ १९२६ स्वामिन्यन्तोदात्तत्वं च ॥

१ । १०५ अजर्यं संगतम् २८५३ ॥ १९२७ अजर्यं कर्तरि ॥

१ । १०६ वदः सुपि क्यप् च २८५४ ॥ १९२८ वदः सुप्यनुपसर्गग्रहणम् ॥

१ । १०८ हनस्त च २८५६ ॥ १९२९ हनस्तश्चिस्त्रियां छन्दसि ॥

१ । १०९ एतिस्तुशास्वृदृजुषः क्यप् २८५७ ॥ १९३० क्यब्विधौ वृञ्ग्रहणम् । १९३१ अञ्जेश्चोप[1]संख्यानम् । १९३२ शंसिदुहिगुहिभ्यो वेति वक्तव्यम् ॥

१ । ११२ भृञोऽसंज्ञायाम् २८६१ ॥ १९३३ भृञः संज्ञाप्रतिषेधे स्त्रियामप्रतिषेधोऽन्येन विहितत्वात् । १९३४ प्रतिषेधः किमर्थ इति चेदस्त्रीसंज्ञाप्रतिषेधार्थः । १९३५ सिद्धं तु स्त्रियां

---

१ इदं काशिकायां वर्तते । तत्र 'प्रशस्य श्रः' 'ईडवन्दवृशंसदुहां ण्यतः' इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम्—इति दीक्षितः ।

संज्ञाप्रतिषेधात्। १९३६ संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिद्ध्यति। १९३७ स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति॥ १९३८ अथ वा बहुलं कृत्याः संज्ञायामिति तत्स्मृतम्। १९३९ यथा यत्यं यथा जन्यं यथा भित्तिस्तथैव सा॥ १९४० समश्च बहुलम्॥

३। १। ११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः २८६५॥ १९४१ सूर्यरुच्याव्यथ्याः कर्तरि। १९४२ कुप्यं संज्ञायाम्। १९४३ कृष्टपच्यस्यान्तोदात्तत्वं च कर्मकर्तरि च॥

३। १। ११८ प्रत्यपिभ्यां ग्रहेः २८६९॥ १९४४ प्रत्यपिभ्यां ग्रहेश्छन्दसि॥

३। १। १२३ छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ३४०७॥ १९४५ हिरण्य इति च वक्तव्यम्॥

३। १। १२४ ऋहलोर्ण्यत् २८७२॥ १९४६ पाणौ सृजेर्ण्यद्विधिः। १९४७ समवपूर्वाच्च। १९४८ लपिदभिभ्यां च॥

३। १। १२५ ओरावश्यके २८८६॥ १९४९ आवश्यक उपपद इति चेद्द्योत्य उपसंख्यानम्। १९५० द्योत्य इति चेत्स्वरसमासानुपपत्तिः। १९५१ ओरावश्यके ण्यतः स्तौतेः क्यप्पूर्वविप्रतिषिद्धम्॥

३। १। १२७ आनाय्योऽनित्ये २८८८॥ १९५२ दक्षिणाग्नाविति वक्तव्यम्॥

३। १। १२९ पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु २८९०। १९५३ पाय्यनिकाय्ययोरादिपत्वकत्वनिपातनम्॥

३। १। १३० क्रतौ कुण्डपाय्यसंचाय्यौ २८९१॥ १९५४ कुण्डपाय्ये यद्विधिः॥

३। १। १३१ अग्नौ परिचाय्योपचाय्यसमूह्याः २८९२॥ १९५५ समूह्य इत्यनर्थकं वचनं सामान्येन कृतत्वात्। १९५६ वह्यर्थमिति चेदूहेस्तदर्थत्वात्सिद्धम्। १९५७ अहिविग्रहार्थं ब्राह्मणे सिद्धम्॥

३। १। १३२ चित्याग्निचित्ये च २८९३॥ १९५८ अग्निचित्यान्तोदात्तः॥

३। १। १३३ ण्वुल्तृचौ २८९५॥ १९५९ ण्वुलि सकर्मकग्रहणम्। १९६० न वा धातुमात्राद्दर्शनाण्ण्वुलः। १९६१ तृजादिषु वर्तमानकालोपादानमध्यायकवेदाध्यायाद्यर्थम्। १९६२ न वा कालमात्रे दर्शनादन्येषाम्॥

३। १। १३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः २८९६॥ १९६३ अजपि सर्वधातुभ्यः। १९६४ पचाद्यनुक्रमणमनुबन्धासञ्जनार्थमपवादबाधनार्थं च॥

३। १। १३५ इगुपधज्ञाप्रीकिरः कः २८९७॥ १९६५ इगुपधेभ्य उपसर्गे कविधिर्मन्दर्थः। १९६६ न वा बुधादीनां दर्शनादनुपसर्गेऽपि॥

३। १। १३७ पाघ्राध्माधेड्दृशः शः २८९९॥ १९६७ जिघ्रः संज्ञायां प्रतिषेधः॥

३। १। १३८ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च २९००। १९६८ अनुपसर्गान्नौ लिम्पेः। १९६९ गवादिषु च विन्देः संज्ञायाम्॥

३। १। १४० ज्वलितिकसन्तेभ्यो णः २९०२॥ १९७० तनोतेर्ण उपसंख्यानम्॥

३। १। १४५ शिल्पिनि ष्वुन् २९०७॥ १९७१ नृतिखनिरञ्जिभ्य इति वक्तव्यम्॥

१ । १४९ प्रुसृल्वः समभिहारे वुन् २९११ ॥ १९७२ प्रुसृल्वः साधुकारिणि वुन्विधानम् ॥

२ । १ कर्मण्यण् २९१३ ॥ १९७३ कर्मणि निर्वर्त्यमानविक्रियमाण इति वक्तव्यम् । १९७४ कर्मणि निर्वर्त्यमानविक्रियमाणे चेद्वेदाध्यायादीनामुपसंख्यानम् । १९७५ यत्र च नियुक्तः । १९७६ ह्वग्रहिनीवहिभ्यश्च । १९७७ अपरिगणनं वा । १९७८ अनभिधानात् । १९७९ अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेन । १९८० शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च । १९८१ ईक्षिक्षमिभ्यां च । १९८२ न त्वम्भोऽभिगमा । १९८३ अन्नादायेति च कृतां व्यत्ययश्छन्दसि ॥

२ । ३ आतोऽनुपसर्गे कः २९१५ ॥ १९८४ कविधौ सर्वत्र प्रसारणिभ्यो डः । १९८५ के हि संप्रसारणप्रसङ्गः ॥

२ । ४ सुपि स्थः २९१६ ॥ १९८६ सुपि स्थो भावे च । १९८७ योगविभागात्सिद्धम् ॥

२ । ५ तुन्दशोकयोः परिमृजापनुदोः २९१९ ॥ १९८८ तुन्दशोकयोः परिमृजापनुदोरालस्यसुखाहरणयोः । १९८९ कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् ॥

२ । ८ गापोष्टक् २९२२ ॥ १९९० सुराशीध्वोः पिबतेः । १९९१ बहुलं तणि ॥

२ । ९ हरतेरनुद्यमनेऽच् २९२३ ॥ १९९२ अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु ग्रहेरुपसंख्यानम् । १९९३ सूत्रे च धार्यर्थे ॥

२ । १३ स्तम्बकर्णयोरमिजपोः २९२७ ॥ १९९४ स्तम्बकर्णयोर्हस्तिसूचकयोः ॥

२ । १४ शमिधातोः संज्ञायाम् २९२८ ॥ १९९५ शमि संज्ञायां धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम् ॥

२ । १५ अधिकरणे शेतेः २९२९ ॥ १९९६ अधिकरणे शेतेः पार्श्वादिषूपसंख्यानम् । १९९७ दिग्धसहपूर्वाच्च । १९९८ उत्तानादिषु कर्तृषु । १९९९ गिरौ डश्छन्दसि । २००० तद्धितो वा ॥

२ । १६ चरेष्टः २९३० ॥ २००१ चरेर्भिक्षाग्रहणं ज्ञापकं कर्मण्यप्रसङ्गस्य ॥

२ । २१ दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु २९३५ ॥ २००२ किंयत्तद्बहुषु कृञोऽज्विधानम् ॥

२ । २४ स्तम्बशकृतोरिन् २९३८ ॥ २००३ स्तम्बशकृतोर्व्रीहिवत्सयोः ॥

२ । २६ फलेग्रहिरात्मंभरिश्च २९४० ॥ २००४ भृञः कुक्ष्यात्मनोर्मुम्च ॥

२ । २८ एजेः खश् २९४१ ॥ २००५ खश्प्रकरणे वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः ॥

२ । २९ नासिकास्तनयोर्ध्माधेटोः २९४४ ॥ २००६ स्तने धेटः । २००७ नासिकायां ध्मश्च धेटश्च । २००८ नासिकानाडीमुष्टिघटीखारीष्विति वक्तव्यम् ॥

२ । ३८ प्रियवशे वदः खच् २९५३ ॥ २००९ खच्प्रकरणे गमेः सुप्युपसंख्यानम् । २०१० विहायसो विह च । २०११ खच्च डिद्वा । २०१२ डे च ॥

२ । ४१ पूःसर्वयोर्दारिसहोः २९५८ ॥ ('२०१३ भगे च दारेः' इति काशिका) ॥

२ । ४८ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः २९६९ ॥ २०१४ डप्रकरणे सर्वत्रपन्नयोरुपसंख्यानम् । २०१५ उरसो लोपश्च । २०१६ सुदुरोरधिकरणे । २०१७ निसो देशे । २०१८ अन्येष्वपि दृश्यते ॥

२ । ४९ आशिषि हनः २९६६ ॥ २०१९ दारावाहनोऽणन्त्यस्य च टः संज्ञायाम् । २०२० चारौ वा । २०२१ कर्मणि समि च ॥

२ । ५५ पाणिघताडघौ शिल्पिनि २९७२ । २०२२ राजघ उपसंख्यानम् ॥

२ । ५६ आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् २९७३ ॥ २०२३ ख्युनि च्विप्रतिषेधानर्थक्यं ल्युट्ख्युनोरविशेषात् । २०२४ मुमर्थमिति चेन्नाव्ययत्वात् । २०२५ उत्तरार्थं तु ॥

२ । ५७ कर्तरि भुवः खिष्णुच्खुकञौ २९७४ ॥ २०२६ इष्णुच इकारादित्वमुदात्तत्वकृतं भुवः । २०२७ नञस्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्णुचः ॥

२ । ५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ३७३ ॥ २०२८ धृषेर्द्विर्वचनमन्तोदात्तत्वं च ॥

२ । ६० त्यदादिषु दृशोऽनालोचने कञ्च ४२९ ॥ २०२९ दृशेः समानान्ययोश्चोपसंख्यानम् । (२०३० 'दृशेः क्सो वक्तव्यः' इति काशिका) । २०३१ कृदर्थानुपपत्तिस्तु । २०३२ इवार्थे तु तद्धितः ॥

२ । ६१ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् २९७५ । २०३३ त्यदादिषु सुब्ग्रहणम् ॥

२ । ६८-६९ अदोऽनन्ने २९७७ । क्रव्ये च २९७८ ॥ २०३४ अदोऽनन्ने क्रव्येग्रहणं वासरूपानिवृत्त्यर्थम् ॥

२ । ७१ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ३४१४ ॥ २०३५ श्वेतवहादीनां डस् । २०३६ पदस्य च । २०३७ वर्थम् ॥

२ । ७८ सुप्यजातौ णिनिस्ताच्छील्ये २९८८ ॥ २०३८ णिन्विधौ साधुकारिण्युपसंख्यानम् । २०३९ ब्रह्मणि वदः ॥

२ । ८३ आत्ममाने खश्च २९९३ ॥ २०४० कर्मकर्तरि च ॥

२ । ८४ भूते २९९५ ॥ २०४१ निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः । २०४२ अव्ययनिर्देशात्सिद्धम् । २०४३ न वा तद्विधानस्यान्यत्राभावात् । २०४४ भूताधिकारस्य प्रयोजनं कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुन्वन्तः सुषुपुषोऽनेहा अग्निमादधानस्य ॥

२ । ८७ ब्रह्मभ्रूणवृत्रेषु क्विप् २९९८ ॥ २०४५ ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम् । २०४६ तथा चोत्तरस्य वचनार्थः ॥

२ । ९३ कर्मणीनिर्विक्रियः ३००३ ॥ २०४७ कर्मणि कुत्सिते ॥

२ । १०१ अन्येष्वपि दृश्यते ३०११ ॥ २०४८ अन्येभ्योऽपि दृश्यते ॥

२ । १०२ निष्ठा ३०१३ ॥ २०४९ निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः । २०५० द्विः क्तक्तवतुग्रहणम् । २०५१ आदिकर्मणि निष्ठा । २०५२ यद्वा भवन्त्यर्थे । २०५३ न्याय्या त्वाद्यपवर्गात् । २०५४ वा चाद्यतन्याम् ॥

२ । १०६–१०७ लिटः कानज्वा ३०९४ । क्वसुश्च ३०९५ ॥ २०५५ कानच्क्वसोर्वावचनं छन्दसि लिङो दर्शनात् । २०५६ न वानेन विहितस्यादेशवचनात् । २०५७ कित्करणं संयोगान्तार्थम् । २०५८ ऋकारान्तगुणप्रतिषेधार्थं वा ॥

२ । १०८ भाषायां सदवसश्रुवः ३०९७ ॥ २०५९ भाषायां सदादिभ्यो वा लिट् । २०६० तद्विषये लुङोऽनिवृत्त्यर्थम् । २०६१ अनद्यतनपरोक्षयोश्च । २०६२ अपवादविप्रतिषेधाद्धि तयोर्भावः । २०६३ तस्य क्वसुरपरोक्षे नित्यम् ॥

२ । १०९ उपेयिवाननाश्वाननूचानश्च ३०९८ ॥ २०६४ उपेयुषि निपातनमिडर्थम् । २०६५ उपेयुषि निपातनमिडर्थमिति चेदजादावतिप्रसङ्गः । २०६६ एकादिष्टस्येड्भावार्थं तु । २०६७ व्यञ्जने यणादेशार्थं वा । २०६८ नोपेयिवान्निपात्यो द्विर्वचनादिड्भविष्यति परत्वात् । २०६९ अन्येषामेकाचां द्विर्वचनं नित्यमित्याहुः । २०७० अस्य पुनरिट् च नित्यो द्विर्वचनं च न विहन्यते ह्यस्य । २०७१ द्विर्वचने चैकाच्त्वात् । २०७२ तस्मादिड्बाधते द्वित्वम् । २०७३ अनूचानः कर्तरि ॥

२ । ११० लुङ् २२१८ ॥ २०७४ लुङ्लटोरपवादप्रसङ्गो भूतभविष्यतोरविशेषवचनात् । २०७५ न वापवादस्य निमित्ताभावादद्यतने हि तयोर्विधानम् । २०७६ वसेर्लुङ् रात्रिशेषे । २०७७ जागरणसंततौ ॥

२ । १११ अनद्यतने लङ् २२०५ ॥ २०७८ अनद्यतन इति बहुव्रीहिनिर्देशोऽद्य ह्यो वाभुङ्क्ष्महीति । २०७९ परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये ॥

२ । ११४ विभाषा साकाङ्क्षे २७७५ ॥ २०८० विभाषा साकाङ्क्षे सर्वत्र ॥

२ । ११५ परोक्षे लिट् २१७१ ॥ २०८१ परोभावः परस्याक्षे परोक्षे लिटि दृश्यताम् । २०८२ उत्वं वादेः परादक्ष्णः । २०८३ सिद्धं वास्मान्निपातनात् ॥ २०८४ परोक्षे लिडत्यन्तापह्नवे च ॥

२ । ११८ लट् स्मे २७७८ ॥ २०८५ स्मेरा भूतमात्रे न स्मपुराद्यतने ॥

२ । १२० ननौ पृष्टप्रतिवचने २७८० ॥ २०८६ ननौ पृष्टप्रतिवचन इत्याशिष्यं क्रियासमाप्तेर्विवक्षितत्वात् ॥

२ । १२२ पुरि लुङ् चास्मे २७८२ ॥ २०८७ ह्शश्वद्भ्यां पुरा । २०८८ स्मः सर्वेभ्यो विप्रतिषेधेन ॥

२ । १२३ वर्तमाने लट् २१५१ ॥ २०८९ प्रवृत्तस्याविरामे शिष्या भवन्त्यवर्तमानत्वात् । २०९० नित्यप्रवृत्ते च कालाविभागात् । २०९१ न्याय्या त्वारम्भानपवर्गात् । २०९२ अस्ति च मुक्तसंशये विरामः । २०९३ सन्ति च कालविभागाः ॥

२ । १२४ लटः शतृशानचावप्रथमासमानाधिकरणे ३१०० ॥ २०९४ लस्याप्रथमासमानाधिकरणेनायोगादादेशानुपपत्तिर्यथान्यत्र । २०९५ योग इति चेदन्यत्रापि योगः स्यात् । २०९६ लटः शतृशानचावप्रथमासमानाधिकरण इति चेत्प्रत्ययोत्तरपदयोरुपसंख्यानम् । २०९७ प्रथमाप्रतिषेध उत्तरपद आदेशानुपपत्तिः । २०९८ सिद्धं तु प्रत्ययोत्तरपदयोश्चेति वचनात् । २०९९ तत्र प्रत्ययस्यादेशनिमित्तत्वादप्रसिद्धिः । २१०० उत्तरपदस्य च सुबन्तनिमित्तत्वाच्छतृशानचोरप्रसिद्धिः । २१०१ न वा लकारस्य कृत्त्वात्प्रातिपदिकत्वम् । २१०२ तिङादेशात्सुबुत्पत्तिः । २१०३ तस्मादुत्तरपदप्रसिद्धिः ॥

२ । १२६ लक्षणहेत्वोः क्रियायाः ३१०३ ॥ २१०४ लक्षणहेत्वोः क्रियाया गुण उ- संख्यानम् । २१०५ कर्तुश्च लक्षणयोः पर्यायेणाचयोगे । २१०६ तत्त्वाख्याने च । २१०७ सदादयश्च बहुलम् । २१०८ इङ्जुहोत्योर्वावचनम् । २१०९ माङ्याक्रोशे ॥

२ । १२७ तौ सत् ३१०६ ॥ २११० तौ सदिति वचनमसंसर्गार्थम् । २१११ अवधारणं लटि विधानम् । २११२ योगविभागतश्च विहितं सत् । २११३ उत्तरयोर्लादेशे वावचनम् । २११४ साधनाभिधानम् । २११५ स्मरः । २११६ उपग्रहप्रतिषेधश्च । २११७ अलादेशे षष्ठीप्रतिषेधः । २११८ द्विषः शतुर्वावचनम् ॥

२ । १३५ तृन् ३११५ ॥ २११९ तृन्विधावृत्विक्षु चानुपसर्गस्य । २१२० नयतेः षुक्च । २१२१ न वा धात्वन्यत्वात् । २१२२ नेषतु नेष्टादिति दर्शनात् । २१२३ त्विषेर्देवतायामकारश्चोपधाया अनिट्त्वं च । २१२४ क्षदेश्च युक्ते । २१२५ छन्दसि तृच ॥

२ । १३९ ग्लाजिस्थश्च क्स्नुः ३११९ ॥ २१२६ स्नोः कित्त्वे स्थ ईकारप्रतिषेधः । २१२७ आकिति गुणप्रतिषेधः । २१२८ गुन इट्प्रतिषेधश्च । २१२९ स्थादंशिभ्यां स्नुश्छन्दसि । २१३० स्नोर्गित्त्वान्न स्थ ईकारः । २१३१ क्ङितोरीत्त्वशासनात् । २१३२ गुणाभावस्त्रिषु स्मार्गः । २१३३ श्र्युकोऽनिट्त्वं गकोरितोः ॥

२ । १४१ शमित्यष्टाभ्यो घिनुण् ३१२१ ॥ २१३४ घिनुण कर्मकाणाम् ॥

२ । १४६ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् ३१२६ ॥ २१३५ वुञनेकाचः । २१३६ निन्दादिभ्यो वुञ्वचनमन्येभ्यो ण्वुलः प्रतिषेधार्थम् । २१३७ तृजादिप्रतिषेधार्थं चेके ॥

२ । १५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ३१३० ॥ २१३८ पदिग्रहणमनर्थकमनुदात्तेतश्च हलादेरिति सिद्धत्वात् । २१३९ असरूपनिवृत्त्यर्थं तु ॥

२ । १५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् ३१३८ ॥ २१४० आलुचि शीङ्ग्रहणम् ॥

२ । १७१ आदृगमहनजनः किकिनौ लिट् च ३१५१ ॥ २१४१ किकिनोः कित्त्वमृकारगुणप्रतिषेधार्थम् । २१४२ उत्सर्गश्छन्दसि सदादिभ्यो दर्शनात् । २१४३ भाषायां धाञ्कृसृजनिनमिभ्यः । २१४४ सासहिवावहिचाचलिपापतीनां निपातनम् ॥

२ । १७४ भियः क्रुक्लुकनौ ३१५४ ॥ २१४५ भियः क्रुकन्नपि वक्तव्यः ॥

२ । १७८ अन्येभ्योऽपि दृश्यते ३१५८ ॥ २१४६ क्विब्विधिरनुपपदार्थः । २१४७ वचि-प्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घश्च । २१४८ वचिप्रच्छ्योरसंप्रसारणं च । २१४९ द्युतिगमिजुहोतीनां द्वे च जुहोतेर्दीर्घश्च । २१५० दृणातेर्ह्रस्वश्च द्वे च किञ्चेति वक्तव्यम् । २१५१ ध्यायतेः संप्रसारणं च ॥

२ । १८० विप्रसंभ्यो ड्वसंज्ञायाम् ३१६० ॥ २१५२ डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानं धातुविधितुक्प्रतिषेधार्थम् ॥

३ । १ उणादयो बहुलम् ३१६१ ॥ २१५३ बाहुलकं प्रकृतेस्तनुदृष्टेः । २१५४ प्रायसमुच्चयनादपि तेषाम् । २१५५ कार्यसशेषविधेश्च तदुक्तम् । २१५६ नैगमरूढिभवं हि सुसाधु

२१५७ नाग च धातुजमाह निरुक्ते । २१५८ व्याकरणे शकटस्य तोकम् । २१५९ यत्र विशेषपदार्थसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥

३ । ३ भविष्यति गम्यादयः ३१७१ ॥ २१६० भविष्यतीत्यनद्यतन उपसंख्यानम् । २१६१ इतरेतराश्रयं च । २१६२ न वा तद्विधानस्यानवकाशत्वात् । २१६३ भविष्यदधिकारस्य प्रयोजनं यावत्पचति पुरा पचतीत्यनपशब्दत्वाय ॥

३ । ४ यावत्पुरानिपातयोर्लट् २७८३ ॥ २१६४ यावत्पुरादिषु लड्विधिर्लुटः पूर्वविप्रतिषिद्धम् ॥

३ । १० तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३१७९ ॥ २१६५ ण्वुलः क्रियार्थोपपदस्य पुनर्विधानं तृजादिप्रतिषेधार्थम् ॥

३ । ११ भाववचनाश्च ३१८० ॥ २१६६ भाववचनानां यथाविहितानां प्रतिपदविध्यर्थम् ॥

३ । १२ अण्कर्मणि च ३१८१ ॥ २१६७ अणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थम् ॥

३ । १३ लृट् शेषे च २१९३ ॥ २१६८ लृटि शेषवचनं क्रियायां प्रतिपदविध्यर्थम् । २१६९ अविशेषेण विधाने लटोऽभावः प्रतिषिद्धत्वात् ॥

३ । १४ लृटः सद्वा ३१०७ ॥ २१७० सद्विधिर्नित्यमप्रथमासमानाधिकरणे ॥

३ । १५ अनद्यतने लुट् २१८५ ॥ २१७१ परिदेवने श्वस्तनी भविष्यन्त्यर्थे । २१७२ कालप्रकर्षात्तु मानम् ॥

३ । १६ पदरुजविशस्पृशो घञ् ३१८२ ॥ २१७३ स्पृश उपतापे ॥

३ । १७ सृ स्थिरे ३१८३ ॥ २१७४ व्याधिमत्स्यबलेष्विति वक्तव्यम् ॥

३ । १८ भावे ३१८४ ॥ २१७५ भावे सर्वलिङ्गो निर्देशः ॥

३ । १९ अकर्तरि च कारके संज्ञायाम् ३१८८ ॥ २१७६ कारकग्रहणमनादेशे स्वार्थविज्ञानात् । २१७७ संज्ञाग्रहणानर्थक्यं सर्वत्र घञो दर्शनात् । २१७८ अतिप्रसङ्ग इति चेदभिधानलक्षणत्वात्प्रत्ययस्य ॥

३ । २० परिमाणाख्यायां सर्वेभ्यः ३१९० ॥ २१७९ सर्वग्रहणमनर्थकं परिमाणाख्यायामिति सिद्धत्वात् । २१८० घञनुक्रमणमजब्विषये । २१८१ अननने हि सोपसर्गणामप्यपवादविज्ञानम् । २१८२ दारजारौ कर्तरि णिलुक् च । २१८३ करणे वा ॥

३ । २१ इङश्च ३१९१ ॥ २१८४ इङश्चेत्यपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष् । २१८५ शॄ वायुवर्णनिवृतेषु ॥

३ । ३६ समि मुष्टौ ३२०८ ॥ २१८६ समि मुष्टावित्यनर्थकं परिमाणाख्यायामिति सिद्धत्वात् । २१८७ अपरिमाणार्थं तु । २१८८ उद्ग्राभनिग्राभौ च छन्दसि स्रगुद्यमननिपातनयोः ॥

३ । ४३ कर्मव्यतिहारे णच् स्त्रियाम् ३२१५ ॥ २१८९ कर्मव्यतिहारे स्त्रीग्रहणं व्यतिपाकार्थम् । २१९० पृथग्ग्रहणं बाधकबाधनार्थम् । २१९१ आचार्यदेशीयानन्यर्थम् । २१९२ तत्र व्यतीक्षादिषु दोषः । २१९३ सिद्धं तु प्रकृते स्त्रीग्रहणे णज्ग्रहणं णिज्ग्रहणं च ॥

३ । ४४ अभिविधौ भाव इनुण् ३२१८ ॥ २१९४ अभिविधौ भावग्रहणं नपुंसके क्तादिनिवृत्त्यर्थम् । २१९५ पृथग्ग्रहणं बाधकबाधनार्थम् । २१९६ न तु ल्युटः ॥

३ । ९६ एरच् ३२३१ ॥ २१९७ अज्विधौ भयादीनामुपसंख्यानम् । २१९८ नपुंसके क्तादिनिवृत्त्यर्थम् । २१९९ कल्यादिभ्यः प्रतिषेधः । २२०० जवसवौ छन्दसि ॥

३ । ९८ ग्रहवृदृनिश्चिगमश्च ३२३४ ॥ २२०१ अब्विधौ निश्चिग्रहणमनर्थकं स्तोयस्य घञ्विधौ प्रतिषेधात् । २२०२ अस्तेयार्थमिति चेन्नानिष्टत्वात् । २२०३ वशिरण्योश्चोपसंख्यानम् । २२०४ घञर्थे कविधानं स्थास्नापाव्यधिहानियुध्यर्थम् ॥

३ । ९० यजयाचयतविच्छप्रच्छरक्षो नङ् ३२६८ ॥ २२०५ यजादिभ्यो नस्य ङित्वे संप्रसारणप्रतिषेधः । २२०६ अङिति गुणप्रतिषेधः ॥

३ । ९४ स्त्रियां क्तिन् ३२७२ ॥ २२०७ स्त्रियां क्तिन्नाबादिभ्यः । २२०८ निष्ठायां वा सेटोऽकारवचनात् ॥

३ । ९५ स्थागापापचो भावे ३२७३ ॥ २२०९ स्थादिभ्यः सर्वापवादप्रसङ्गः । २२१० सिद्धं त्वङ्विधाने स्थादिप्रतिषेधात् । २२११ श्रुयजिषिस्तुभ्यः करणे । २२१२ ग्लाज्याहाभ्यो निः ॥

३ । ९८ व्रजयजोर्भावे क्यप् ३२७५ ॥ २२१३ क्यब्विधिरधिकरणे च ॥

३ । १०० कृञः श च ३२७७ ॥ २२१४ कृञः श चेति वावचनं क्तिन्नर्थम् ॥

३ । १०१ इच्छा ३२७८ ॥ २२१५ इच्छापरिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम् । २२१६ जागर्तेरकारो वा ॥

३ । १०४ षिद्भिदादिभ्योऽङ् ३२८१ ॥ २२१७ भिदा विदारणे । २२१८ छिदा द्वैधीकरणे । २२१९ आरा शस्त्र्याम् । २२२० धारा प्रपाते । २२२१ गुहा गिर्योषध्योः ॥

३ । १०७ ण्यासश्रन्थो युच् ३२८४ ॥ २२२२ युच्प्रकरणे घट्टिवन्दिविदिभ्य उपसंख्यानम् । २२२३ इषेरनिच्छार्थस्य । २२२४ परेर्वा ॥

३ । १०८ रोगाख्यायां ण्वुल्बहुलम् ३२८५ ॥ २२२५ धात्वर्थनिर्देशे ण्वुल् । २२२६ इक्श्तिपौ धातुनिर्देशे । २२२७ वर्णात्कारः । २२२८ रादिफः । २२२९ मत्वर्थाच्छः । २२३० इणजादिभ्यः । २२३१ इञ्वपादिभ्यः । २२३२ इक्कृष्यादिभ्यः । २२३३ संपदादिभ्यः क्विप् ॥

३ । ११३ कृत्यल्युटो बहुलम् २८४१ ॥ २२३४ कृतो बहुलमिति वक्तव्यं पादहारकाद्यर्थम् ॥

३ । ११९ गोचरसंचरवहव्रजव्यजापणनिगमाश्च ३२९८ ॥ २२३५ गोचरादीनामग्रहणं प्रायवचनाद्यथा कषो निकष इति ॥

३ । १२१ हलश्च ३३०० ॥ २२३६ घञ्विधाववहाराधारावायानामुपसंख्यानम् ॥

३ । १२३ उदङ्कोऽनुदके ३३०२ ॥ २२३७ उदङ्कोऽनुदकवचनानर्थक्यं च प्रायवचनाद्यथा गोदोहनः प्रसाधन इति ॥

३ । १२५ खनो घ च ३३०४ ॥ २२३८ खनो डडरेकेकवकाः ॥

३ । १२६ ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ३३०५ ॥ २२३९ अजब्भ्यां स्त्रीखलनाः । २२४० स्त्रियाः खलनौ विप्रतिषेधेन ॥

३ । १२७ कर्तृकर्मणोश्च भूकृञोः ३३०८ २२४१ खल्कर्तृकर्मणोश्च्व्यर्थयोः । २२४२ कर्तृकर्मग्रहणं चोपपदार्थम् ॥

३ । १३० अन्येभ्योऽपि दृश्यते ३४२२ ॥ २२४३ भाषायां शासियुधिदृशिधृषिभ्यो युच् । २२४४ मृषेश्चेति वक्तव्यम् ॥

३ । १३१ वर्तमानसामीप्ये वर्तमानवद्वा २७८९ ॥ २२४५ वर्तमानसामीप्ये वर्तमानवद्वचनं शत्राद्यर्थम् ॥

३ । १३२ आशंसायां भूतवच्च २७९० ॥ २२४६ आशंसायां भूतवदतिदेशे लङ्लिटोः प्रतिषेधः । २२४७ न वाप्रत्ययस्य निमित्ताभावादनद्यतने हि तयोर्विधानम् । २२४८ आशंसासंभावनयोरविशेषात्तद्विधानस्याप्राप्तिः । २२४९ न वा संभावनानद्यतनत्वादाशंसायाः । २२५० अर्थासंदेहो वालमर्थत्वात्संभावनस्य ॥

३ । १३३ क्षिप्रवचने लृट् २७९१ ॥ २२५१ क्षिप्रवचने लृट आशंसावचने लिङ्प्रतिषेधेन । २२५२ अनिष्पन्ने निष्पन्नशब्दः शिष्योऽनिष्पन्नत्वात् । २२५३ सिद्धं तु भविष्यत्प्रतिषेधात् । २२५४ हेतुभूतकालसंप्रेक्षितत्वाद्वा । २२५५ अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तय कर्तुर्विद्यमानत्वात् । २२५६ सिद्धं तु यथास्वकालं समुच्चारणात् । २२५७ अवात्वात् । २२५८ असिद्धविपर्यासश्च ॥

३ । १३५ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः २७९३ ॥ २२५९ नानद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः । २२६० अद्यतनवद्विधाने हि विधानम् । २२६१ तत्र लङ्विधिप्रसङ्गः । २२६२ लुङ्लृटोश्चायथाकालम् ॥

३ । १३६ भविष्यति मर्यादावचनेऽवरस्मिन् २७९४ ॥ २२६३ भविष्यति मर्यादावचनेऽवरस्मिन्नित्यक्रियाप्रबन्धार्थम् । २२६४ क्रियाप्रबन्धार्थमिति चेद्वचनानर्थक्यम् । २२६५ अहोरात्रप्रतिषेधार्थमिति चेन्नानिष्टत्वात् ॥

३ । १३७ कालविभागे चानहोरात्राणाम् २७९५ ॥ २२६६ अनहोरात्राणामिति तद्विभागे प्रतिषेधः । २२६७ तैश्च विभागे ॥

३ । १४० भूते च २७९७ ॥ २२६८ भूते लङ्क्ताप्यादिषु ॥

३ । १४१ वोताप्योः २७९८ ॥ २२६९ विभाषा गर्हाप्रभृतौ प्रागुताप्यिभ्याम् ॥

३ । १४२ गर्हायां लडपिजात्वोः २७९९ ॥ २२७० गर्हायां लड्विधानानर्थक्यं क्रियासमाप्तिविवक्षितत्वात् ॥

३ । १४५ अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि २८०२ ॥ २२७१ किंवृत्तस्यानधिकारादुत्तरत्राकिंवृत्तग्रहणानर्थक्यम् ॥

३ । १४७ जातुयदोर्लिङ् २८०४ ॥ २२७२ जातुयदोर्लिङ्विधाने यदायद्योरुपसंख्यानम् ॥

३ । १५१ शेषे लृडयदौ २८०८ ॥ २२७३ चित्रीकरणे यदिप्रतिषेधानर्थक्यमर्थान्यत्वात् ॥

३ । १५६ हेतुहेतुमतोर्लिङ् २८१३ ॥ २२७४ हेतुहेतुमतोर्लिङ्वा । २२७५ भविष्यदधिकारे ॥

३ । १५७ इच्छार्थेषु लिङ्लोटौ २८१४ ॥ २२७६ कामप्रवेदनं चेत् ॥

३ । १६१ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् २२०८ ॥ २२७७ निमन्त्रणादीनामर्थे चेदामन्त्रये निमन्त्रये भवन्तमिति प्रत्ययानुपपत्तिः प्रकृत्यभिहितत्वात् ।

२२७८ द्विवचनबहुवचनाप्रसिद्धिश्चैकार्थत्वात् । २२७९ सिद्धं तु द्वितीयाकाङ्क्षस्य प्रकृते प्रत्यार्थे प्रत्ययविधानात् ॥

३ । १६३ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च २८१७ ॥ २२८० प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टम् । २२८१ विध्यर्थं तु स्त्रियाः प्रागिति वचनात् ॥

३ । १६७ । कालसमयवेलासु तुमुन् ३१७९ ॥ २२८२ प्रथमान्तेष्विति वक्तव्यम् ॥

४ । १ धातुसंबन्धे प्रत्ययाः २८२४ ॥ २२८३ धातुसंबन्धे प्रत्ययस्य यथाकालविधानात्सिद्धम् । २२८४ उपपदस्य कालान्यत्वम् ॥

४ । २ क्रियासमभिहारे लोट् । लोटो हिस्वौ वा च तध्वमोः २८२९ ॥ २२८५ हिस्वयोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थम् । २२८६ समसंख्यार्थं च । २२८७ न वा तध्वमोरादेशवचनं ज्ञापकं पदादेशस्य । २२८८ तत्र पदादेशे पित्त्वाटोः प्रतिषेधः । २२८९ सिद्धं तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् । २२९० योगविभागात्सिद्धम् ॥

४ । ८ उपसंवादाशङ्कयोश्च ३४३१ ॥ २२९१ उपसंवादाशङ्कयोर्वचनानर्थक्यं लिङर्थत्वात् ॥

४ । २१ समानकर्तृकयोः पूर्वकाले ३३२० ॥ २२९२ समानकर्तृकयोरिति बहुप्रप्राप्तिः । २२९३ द्विवचननिर्देशात् । २२९४ सिद्धं तु क्रियाप्रधानत्वात् । २२९५ लोकविज्ञानाच्च सिध्यति । २२९६ अनन्त्यवचनात्तु सिद्धम् । २२९७ व्यादाय स्वपितीत्युपसंख्यानमपूर्वकालत्वात् । २२९८ न वा स्वप्नस्यावरकालत्वात् ॥

४ । २४ विभाषाग्रेप्रथमपूर्वेषु ३३४९ ॥ २२९९ अग्रादिष्वप्राप्तविधेः समासप्रतिषेधः ॥

४ । २६ स्वादुमि णमुल् ३३४७ ॥ २३०० स्वादुमि मान्तनिपातनमीकाराभावार्थम् । २३०१ च्व्यन्तस्य मकारान्तार्थम् । २३०२ आ च तुमुनः समानाधिकरणे ॥

४ । ३७ करणे हनः ३३५८ ॥ २३०३ हनः करणेऽनर्थकं वचनं हिंसार्थेभ्यो णमुल्विधानात् । २३०४ अर्थवत्त्वहिंसार्थस्य विधानात् २३०५ नित्यसमासार्थं च ॥

४ । ६७ कर्तरि कृत् २८३२ ॥ २३०६ कर्तरि कृद्वचनमनादेशे स्वार्थविज्ञानात् । २३०७ तत्र ख्युनादिप्रतिषेधो नानावाक्यत्वात् । २३०८ तद्वच्च कृत्येष्वेवकारकरणम् । २३०९ तत्र भव्याद्यर्थम् । २३१० ऋषिदेवतयोः कर्तरि समावेशवचनं ज्ञापकमसमावेशस्य । २३११ एवकारकरणं चार्थे । २३१२ तच्च भव्याद्यर्थम् । २३१३ तत्र प्रत्ययनियमेऽनिष्टप्रसङ्गः । २३१४ संज्ञानियमे सिद्धम् । २३१५ विभक्त्यादिषु चाप्राप्तिः प्रकृतेः प्रत्ययपरवचनात् ॥

४ । ६९ लः कर्मणि च भावे चाकर्मकेभ्यः २१५२ ॥ २३१६ लग्रहणं सकर्मकनिवृत्त्यर्थम् । २३१७ विप्रतिषेधाद्भानः कर्तरि । २३१८ सर्वप्रसङ्गस्तु । २३१९ सर्वत्राप्रसङ्गस्तु । २३२० सर्वप्रसङ्गस्तु ॥

४ । ७७ लस्य २१५३ ॥ २३२१ लादेशे सर्वप्रसङ्गोऽविशेषात् । २३२२ अर्थवद्ग्रहणात्सिद्धम् । २३२३ अर्थवद्ग्रहणात्सिद्धमिति चेन्न वर्णग्रहणेषु । २३२४ तस्माद्वंशिष्टग्रहणम् । २३२५ लादेशो वर्णविधेः पूर्वविप्रतिषिद्धम् ॥

४ । ७९ टित आत्मनेपदानां टेरे २२३३ ॥ २३२६ टित एत्व आत्मनेपदेष्वानप्रतिषेधः ॥

४। ८२ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः २१७३ ॥ २३२७ णलः शित्करणं सर्वादेशार्थम्। २३२८ अकारस्य शित्करणं सर्वादेशार्थम्। २३२९ अकारवचनं समसंख्यार्थम्। २३३० तस्माच्छित्करणम्॥

४। ८५ लोटो लङ्वत् २१९८॥ २३३१ लङ्वदतिदेशे जुस्भावप्रतिषेधः। २३३२ उत्ववचनात्सिद्धम्॥

४। ८७-८९ सेर्ह्यपिच्च २२०१। मेर्निः २२०३ ॥ २३३३ हिन्योरुत्वंप्रतिषेधः। २३३४ न वोच्चारणसामर्थ्यात्॥

४। ९३ एत ऐ २२९३॥ २३३५ एत ऐत्व आट्गुणप्रतिषेधः। २३३६ न वा बहिरङ्गलक्षणत्वात्॥

४। १०२ लिङः सीयुट् २२९९॥ २३३७ यासुडादेः सीयुट्प्रतिषेधः। २३३८ न वा वाक्यापकर्षात्। २३३९ सुट्तिथोस्त्वपकर्षविज्ञानात्। २३४० अनादेश्च सुड्वचनम्। २३४१ न वा तिथोः प्रधानभावात्तद्विशेषणं लिङ्ग्रहणम्॥

४। १०३ यासुट् परस्मैपदेषूदात्तो ङिच्च २२०९॥ २३४२ यासुटो ङिद्वचनं पिदर्थम्। २३४३ उदात्तवचनं च। २३४४ आगमानुदात्तार्थं वा॥

४। ११० आतः २२२७॥ २३४५ जुस्याकारग्रहणं नियमार्थमिति चेत्सिज्लुग्ग्रहणम्। २३४६ प्रापकमिति चेत्प्रत्ययलक्षणप्रतिषेधः। २३४७ एवकारकरणं च। २३४८ लङ्ग्रहणं च॥

४। ११४ आर्धधातुकं शेषः २१८७॥ २३४९ आर्धधातुकसंज्ञायां धातुग्रहणम्। २३५० स्वादिप्रतिषेधः। २३५१ तद्विधानात्सिद्धम्॥

इति तृतीयोऽध्यायः।

चतुर्थोऽध्यायः।

१। १ ङ्याप्प्रातिपदिकात् १८२॥ २३५२ ङ्याप्प्रातिपदिकग्रहणमङ्गभपदसंज्ञार्थम्। २३५३ यच्छयोश्च लुगर्थम्। २३५४ वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्संप्रत्ययार्थम्। २३५५ ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्। २३५६ प्रयोजनं सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम्। २३५७ मानिनि च विधिप्रतिषेधार्थम्। २३५८ प्रत्ययग्रहणोपचारेषु च। २३५९ अतिप्रसङ्ग उपपदविधौ। २३६० यञिञोः फकि। २३६१ समासान्तेषु च। २३६२ महदात्वे प्रियादिषु। २३६३ ञ्नित्स्वरे। २३६४ राज्ञः स्वरे ब्राह्मणकुमारयोः। २३६५ समाससंघातग्रहणेषु च। २३६६ तद्धितविधानार्थं तु। २३६७ विप्रतिषेधाद्धि तद्धितबलीयस्त्वम्। २३६८ तत्र समासान्तेषु दोषः। २३६९ त्यूङोश्च ग्रहणम्। २३७० तदन्तस्य च प्रत्ययार्थेनायोगात्तद्धितानुत्पत्तिः॥

१। ३ स्त्रियाम् ४९३॥ २३७१ लिङ्गात्स्त्रीपुंसयोर्ज्ञाने भ्रुकुंसे टाप्प्रसज्यते। २३७२ नत्वं खरकुटीः पश्य। २३७३ खट्वावृक्षौ न सिध्यतः॥ २३७४ नपुंसकं भवेत्तस्मिन्। २३७५ तदभावे नपुंसकम्। २३७६ असत्तु मृगतृष्णावत्। २३७७ गन्धर्वनगरं यथा॥ २३७८ आदित्यगतिवत्सन्न। २३७९ वस्त्रान्तर्हितवच्च तत्। २३८० तयोस्तु तत्कृतं दृष्ट्वा। २३८१ यथाकाशेन ज्योतिषः॥ २३८२ अन्योन्यसंश्रयं त्वेतत्। २३८३ प्रत्यक्षेण विरुध्यते। २३८४

तटे च सर्वलिङ्गानि दृष्ट्वा कोऽध्यवसास्याति ॥ २३८५ संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृता-न्ततः । २३८६ संस्त्याने स्त्यायतेर्ड्रट् स्त्री सूतेः सप् प्रसवे पुमान् ॥ २३८७ तस्योक्तौ लोकतो नाम । २३८८ गुणो वा लुपि युक्तवत् ॥ २३८९ स्त्रियामिति स्त्र्यर्थाभिधाने चेट्टाबादयो द्वि-वचनबहुवचनानेकप्रत्ययानुपपत्तिः । २३९० एकत्वात्स्त्रीत्वस्य । २३९१ स्त्र्यर्थस्य च प्राति-पदिकार्थत्वात्स्त्रियामिति लिङ्गानुपपत्तिः । २३९२ स्त्रीसमानाधिकरणादिति चेद्भूतादिष्वति-प्रसङ्गः । २३९३ षट्संज्ञकेभ्यश्च प्रतिषेधः । २३९४ सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वा-त्स्वार्थे टाबादयः । २३९५ गुणवचनस्य चाश्रयतो लिङ्गवचनभावात् । २३९६ भावस्य च भावयुक्तत्वात् । २३९७ स्त्रीविषये ङ्याप्पोरप्रसिद्धिरकारान्तादर्शनात् । २३९८ सर्वेषां तु स्वर-वर्णानुपूर्वीज्ञानार्थ उपदेशः । २३९९ तस्मात्सिद्धम् ॥

१ । ४ अजाद्यतष्टाप् ४५४ ॥ २४०० शूद्रा चामहत्पूर्वा । २४०१ जातिः ॥

१ । ६ उगितश्च ४५५ ॥ २४०२ धातोरुगितः प्रतिषेधः । २४०३ अञ्चतेश्चोपसंख्यानम् । २४०४ उगित्यञ्चतिग्रहणात्सिद्धमधातोः ॥

१ । ७ वनो र च ४५६ ॥ २४०५ वनो न हशः । २४०६ बहुलं छन्दसि । २४०७ रवि-धाने बहुव्रीहेरुपसंख्यानं प्रतिषिद्धत्वात् । २४०८ अनो बहुव्रीहिप्रतिषेधे वोपधालोपिनो वावचनम् ॥

१ । १० न षट्स्वस्रादिभ्यः ३०८ ॥ २४०९ षट्संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात् । २४१० प्रत्याहाराच्चापा सिद्धम् । २४११ दोषस्त्वत्वे । २४१२ तस्मान्नोभौ ॥

१ । १४ अनुपसर्जनात् ४६९ ॥ २४१३ अनुपसर्जनग्रहणमनर्थकं प्रातिपदिकेन तदन्त-विधिप्रतिषेधात् । २४१४ ज्ञापकं तु पूर्वत्र तदन्ताप्रतिषेधस्य । २४१५ पूर्वसूत्रनिर्देशो वापि-शलमधीत इति । २४१६ जातिशब्देभ्यस्त्वतिप्रसङ्गः । २४१७ सिद्धं तु जातेरनुपसर्जनत्वात् । २४१८ अनुपसर्जनाधिकारे जातेर्ङीष्विधाने सुपर्ण्या उपसंख्यानम् । २४१९ न वा समास-स्यानुपसर्जनत्वाज्जातिवाचकत्वाच्च शब्दस्य सामान्येन ङीष्विधानम् ॥

१ । १५ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ४७० ॥ २४२० ढग्रहणे सानुबन्धकस्योपसंख्यानम् । २४२१ अननुबन्धकग्रहणे हि न सानुबन्धकस्य । २४२२ अञ्ग्रहणमनर्थकं तदन्ताद्धि ङीन्विधानम् । २४२३ न वा जात्यधिकारात् । २४२४ अनधि-कारे हि पुंयोगादाख्यायां ङीन्प्रसङ्गः । २४२५ नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् ॥

१ । १६ यञश्च ४७१ ॥ २४२६ आपत्यग्रहणं द्वीपाद्यञः प्रतिषेधार्थम् ॥

१ । १७ प्राचां ष्फस्तद्धितः ४७३ ॥ २४२७ तद्धितवचनं षितः प्रातिपदिकादीकारार्थम् ॥

१ । १८ सर्वत्र लोहितादिकतन्तेभ्यः ४७६ ॥ २४२८ लोहितादिषु शाकल्यस्योपसं-ख्यानम् । २४२९ कण्वात्तु शकलः पूर्वः । २४३० कतादुत्तर इष्यते । २४३१ पूर्वोत्तरौ तदन्तादी । २४३२ ष्फाणौ तत्र प्रयोजनम् ॥

१ । १९ कौरव्यमाण्डूकाभ्यां च ४७७ ॥ २४३३ कौरव्यमाण्डूकयोरासुरेरुपसंख्या-नम् । २४३४ छश्च ॥

१ । २० वयसि प्रथमे ४७८ ॥ २४३५ वयस्यचरम इति वक्तव्यम् ॥

१ । २९ बहुव्रीहेरूधसो ङीष् ४८४ ॥ २४३६ ऊधसो नकारो लिङ्गाधिकारे । २४३७ न वा समासान्ते स्त्रीग्रहणात् । २४३८ इतरथा हि कब्विधिप्रसङ्गः ॥

१ । २७ दामहायनान्ताच्च ४८६ ॥ २४३९ दामहायनान्तात्संख्यादेः । २४४० तत्पुरुषविज्ञानाद्वा सिद्धम् । २४४१ हायनो वयसि स्मृतः ॥

१ । ३१ रात्रेश्चाजसौ ३४४९ ॥ २४४२ अजसादिष्विति वक्तव्यम् ॥

१ । ३२ अन्तर्वत्पतिवतोर्नुक् ४८९ ॥ २४४३ अन्तर्वत्पतिवदिति गर्भभर्तृसंयोगे । २४४४ अन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात् । २४४५ गर्भिण्यां जीवपत्यां च । २४४६ वा च छन्दसि नुग्भवेत् ॥

१ । ३४ विभाषा सपूर्वस्य ४९१ ॥ २४४७ पत्युः सपूर्वादुपसर्जनसमास उपसंख्यानम् । २४४८ सिद्धं तु पत्युः प्रातिपदिकविशेषणत्वात् ॥

१ । ३६ पूतक्रतोरै च ४९३ ॥ २४४९ पूतक्रत्वादीनां पुंयोगप्रकरणे वचनम् । २४५० लिङ्गसंनियोगेन सर्वत्रागमादेशानां वचने लिङ्गलुकि तत्कृतप्रसङ्गः । २४५१ सिद्धं त्वागमादेशानामङ्गतः स्त्रीप्रकरणे वचनात् । २४५२ लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् ॥

१ । ३९ वर्णादनुदात्तात्तोपधात्तो नः ४९६ ॥ २४५३ असितपलितयोः प्रतिषेधः । २४५४ छन्दसि क्नमेके । २४५५ वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानम् ॥

१ । ४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ५०० ॥ २४५६ नीलादोषधौ । २४५७ प्राणिनि च । २४५८ वा संज्ञायाम् ॥

१ । ४४ वोतो गुणवचनात् ५०२ ॥ २४५९ गुणवचनान्ङीबाद्युदात्तार्थम् । २४६० खरुसंयोगोपधप्रतिषेधश्च ॥

१ । ४८ पुंयोगादाख्यायाम् ५०४ ॥ २४६१ गोपालकादीनां प्रतिषेधः । २४६२ पुंयोगादाख्यायां तद्धितलुग्वचनम् । २४६३ सुबन्तसमासवचनाच्चाकारान्तानुपपत्तिः । २४६४ सिद्धं तु स्त्रियाः पुंशब्देनाभिधानात् । २४६५ गतिकारकोपपदानां कृद्भिः सह समासवचनम् । २४६६ प्रयोजनं कादल्याख्यायाम् । २४६७ जातिर्ङीब्विधानम् । २४६८ समासान्तस्य णत्वे । २४६९ कृदन्ताच्चद्धिते वृद्धिस्वरौ च । २४७० अवदातायां ङीप्प्रतिषेधः । २४७१ सूर्याद्देवतायां चाब्वक्तव्यः ॥

१ । ४९ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ५०५ ॥ २४७२ हिमारण्ययोर्महत्त्वे । २४७३ यवाद्दोषे । २४७४ यवनाल्लिप्याम् । २४७५ उपाध्यायमातुलाभ्यां वा । २४७६ मुद्गलाच्छन्दसि लिच्च । २४७७ आचार्यादणत्वं च । २४७८ अर्यक्षत्रियाभ्यां वा ॥

१ । ५२ बहुव्रीहेश्चान्तोदात्तात् ५०८ ॥ २४७९ अन्तोदात्ते जातप्रतिषेधः । २४८० पाणिगृहीत्यादीनां विशेषे । २४८१ बहुलं तणि । २४८२ प्रवृद्धविलूनाद्यर्थम् । २४८३ अन्तोदात्तादबहुनञ्सुकालसुखादिपूर्वात् । २४८४ जातिपूर्वाद्वा ॥

१ । ५४ स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ५१० ॥ २४८५ उपसर्जनग्रहणमनर्थकं

बहुव्रीह्यधिकारात् । २४८६ बह्वजर्थमिति चेत्स्वाङ्गग्रहणात्सिद्धम् । २४८७ अनन्तोदात्तार्थ-
मिति चेत्सहादिकृतत्वात्सिद्धम् । २४८८ स्वाङ्गसमुदायप्रतिषेधार्थं तु ॥

१ । ५९ नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ५११ ॥ २४८९ नासिकादीनां विभा-
षायां पुच्छाच्च । २४९० कबरमणिविषशरेभ्यो नित्यम् । २४९१ उपमानात्पक्षाच्च पुच्छाच्च ।
२४९२ नासिकादिभ्यो विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधो विप्रतिषेधेन ॥

१ । ६० दिक्पूर्वपदान्ङीप् ५१५ ॥ २४९३ दिक्पूर्वपदान्ङीषोऽनुदात्तत्वम् । २४९४
ङीब्विधाने ह्यन्यत्रापि ङीब्विषयान्ङीप्प्रसङ्गः ॥

१ । ६३ जातेरस्त्रीविषयादयोपधात् ५१८ ॥ २४९५ योपधप्रतिषेधे गवयहयमुकयम-
नुष्यमत्स्यानामप्रतिषेधः ॥

१ । ६४ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ५१९ ॥ २४९६ सदच्काण्ड-
प्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधः । २४९७ संभस्त्राजिनशणपिण्डेभ्यः फलात् । २४९८ श्वेताच्च ।
२४९९ त्रेश्च । २५०० मूलान्नञः ॥

१ । ६५ इतो मनुष्यजातेः ५२० ॥ २५०१ इतो मनुष्यजातेरिञ उपसंख्यानम् ॥

१ । ६६ ऊङुतः ५२१ ॥ २५०२ ऊङ्प्रकरणेऽप्राणिजातेश्चारज्ज्वादीनाम् ॥

१ । ७० संहितशफलक्षणवामादेश्च ५२५ ॥ २५०३ सहितसहाभ्यां चेति वक्तव्यम् ॥

१ । ७१ कद्रुकमण्डल्वोश्छन्दसि ३४४९ ॥ २५०४ कद्रुकमण्डलुगुग्गुलुमधुजतुपत-
यालूनामिति वक्तव्यम् ॥

१ । ७४ यङश्चाप् ५२८ ॥ २५०५ षाच्च यञश्चाप् ॥

१ । ७५ आवट्याच्च ५२९ ॥ २५०६ अन उपधालोपिन ऊधसो ङीष् पूर्वविप्रतिषिद्धम् ।
२५०७ आवट्याद्यायञः ष्फश्चापः ॥

१ । ७८ अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ्गोत्रे ११९८ ॥ २५०८ प्रकर्षे चोत्तमं
कृत्वा दाक्ष्या नोपोत्तमं गुरु । २५०९ आम्विधिः केन ते न स्यात्प्रकर्षे यद्ययं तमः ॥ २५१०
उद्गतस्य प्रकर्षोऽयं गतशब्दोऽत्र लुप्यते । २५११ नाव्ययार्थप्रकर्षोऽस्ति धात्वर्थोऽत्र प्रकृ-
ष्यते ॥ २५१२ उद्गतोऽपेक्षते किंचित्त्रयाणां द्वौ किलोद्गतौ । २५१३ चतुष्प्रभृति कर्तव्ये
वाराह्यायां न सिध्यति ॥ २५१४ भिद्यतेऽस्य स्वरस्तेन विधिश्चापो न लक्ष्यते । २५१५
शब्दान्तरमिदं विद्यादृष्टमभ्यन्तरं त्रिषु ॥ २५१६ ष्यङ्चनादेशे यलोपवचनम् । २५१७ द्वि-
र्विधिः । २५१८ आदेशे नलोपवचनम् । २५१९ न वा ष्यङो लोपनिमित्तत्वात् । २५२० अनु-
बन्धौ त्वया कार्यौ । २५२१ चावर्थम् । २५२२ टाब्विधिर्मम । २५२३ उक्तेऽपि हि भव-
न्त्येते । २५२४ तेन ञित्र भविष्यति ॥ २५२५ अस्थानिवत्त्वे दोषस्ते वृद्धिरत्र न सिध्यति ।
२५२६ त्वयाप्यत्र विशेषार्थं कर्तव्यं स्याद्विशेषणम् ॥ २५२७ पारयायां ते कथं न स्यात् ।
२५२८ एको मे स्याद्विशेषणम् । २५२९ अन्यस्मिन्सूत्रभेदः स्यात् । २५३० ङिति लिङ्गं प्रयु-
ज्यते ॥ २५३१ ङिति चेत्क्रीयिते दोषः । २५३२ व्यवधानान्न दुष्यति । २५३३ योऽजनन्तरो
न धातुः सः । २५३४ यो धातुः सोऽननन्तरः ॥ २५३५ न चेदुभयतः साम्यमुभयत्र प्रसज्यते ॥
२५३६ यङा विशेष्येत यदीह धातुर्यङ् धातुना वा यदि तुल्यमेतत् । २५३७ उभौ प्रधानं
यदि नात्र दोषः । २५३८ तथा प्रसार्येत तु वाक्पतिस्ते ॥ २५३९ धातुप्रकरणस्येह न स्थान-

मिति निश्चयः। २५४० आत्वार्थं यदि कर्तव्यं तत्रैवैतत्करिष्यते॥ २५४१ उपदेशे यदेजन्तं तस्य चेदात्वमिष्यते। २५४२ उद्देशो रूढिशब्दानां तेन गोर्न भविष्यति॥

१। ७९ गोत्रावयवात् ११९९॥ २५४३ गोत्रावयवादगोत्रार्थमिति चेत्तदनिष्टम्। २५४४ गोत्रादिति चेद्वचनानर्थक्यम्। २५४५ अगुरूपोत्तमार्थमिति चेत्सर्वेषामवयवत्वात्सर्वप्रसङ्गः। २५४६ सिद्धं तु रौढ्यादिषूपसंख्यानात्॥

१। ८२ समर्थानां प्रथमाद्वा १०७२॥ २५४७ समर्थवचनमनर्थकं न ह्यसमर्थेनार्थाभिधानम्। २५४८ प्रथमवचनमनर्थकं न ह्यप्रथमेनार्थाभिधानम्॥

१। ८३ प्राग्दीव्यतोऽण् १०७३॥ २५४९ प्राग्वचनं सकृद्विधानार्थम् २५५० अधिकारात्सिद्धमिति चेदपवादविषयेऽण्प्रसङ्गः। २५५१ तस्मात्प्राग्वचनम्। २५५२ न वा क्वचिद्वावचनात्॥

१। ८५ दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः १०७७॥ २५५३ वाङ्मतिपितृमतां छन्दस्युपसंख्यानम्। २५५४ पृथिव्या ञाञौ। २५५५ देवस्य यञञौ। २५५६ बहिषष्टिलोपो यञ्च। २५५७ ईकक्च। २५५८ ईकञ्छन्दसि। २५५९ स्थाम्नोऽकारः। २५६० लोम्नोऽपत्येषु बहुषु। २५६१ सर्वत्र गोरजादिप्रसङ्गे यत्। २५६२ ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषिद्धम्॥

१। ८६ उत्सादिभ्योऽञ् १०७८॥ २५६३ अञ्प्रकरणे ग्रीष्मादच्छन्दसि॥

१। ८७ स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् १०७९॥ २५६४ नञ्स्नञौ भवनाच्चेद्वत्यर्थे प्रतिषेधः। २५६५ वतेः प्रागिति चेद्भाव उपसंख्यानम्॥

१। ८८ द्विगोर्लुगनपत्ये १०८०॥ २५६६ द्विगोर्लुकि तन्निमित्तग्रहणम्। २५६७ अर्थविशेषासंप्रत्ययेऽतन्निमित्तादपि॥

१। ८९ गोत्रेऽलुगचि १०८१॥ २५६८ विप्रतिषेधात्तु लुकश्छविधानम्। २५६९ भूनीति च लुक्प्राप्तो वाद्ये चार्थे विधीयतेऽजादिः। बहिरङ्गमन्तरङ्गाद्विप्रतिषेधादयुक्तं स्यात्॥ भूम्नि प्राप्तस्य लुको यदजादौ तद्धितेऽलुकं शास्ति। एतद्ब्रवीति कुर्वन्समानकालावलुग्लुक्च॥ २५७० यदि वा लुकः प्रसङ्गे भवत्यलुक् छस्तथा प्रसिद्धोऽस्य। २५७१ लुग्वालुकः प्रसङ्गं प्रतीक्षते छेऽलुगस्य तथा। २५७२ गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक्। २५७३ एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि। २५७४ गर्गभार्गविकाग्रहणं वा नियमार्थम्॥

१। ९० यूनि लुक् १०८३॥ २५७५ यूनि लुगचीति चेत्प्रत्ययस्यायथेष्टप्रसङ्गः। २५७६ सिद्धं त्वविशेषेण लुग्वचनं हलि च प्रतिषेधः। २५७७ प्रयोजनं सौवीरगोत्रेभ्यो फाण्टाहृतिमिमताभ्यां णफिञौ। २५७८ इञ्यौ सर्वत्र। २५७९ प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदतिदेशः। २५८० राजन्याद्वुञ्मनुष्याच्च ञाश्च लौकिकं परम्॥

१। ९२ तस्यापत्यम् १०८८॥ २५८१ तस्येदमित्यपत्येऽपि। २५८२ बाधनार्थं कृतं भवेत्। २५८३ उत्सर्गः शेष एवासौ। २५८४ वृद्धान्यस्य प्रयोजनम्॥ २५८५ तद्धितार्थनिर्देशे लिङ्गवचनमप्रमाणं तस्याविवक्षितत्वात्। २५८६ सर्वनामनिर्देशे विशेषासंप्रत्ययः सामान्यनिर्देशात्। २५८७ सामान्यचोदनास्तु विशेषेषु। २५८८ अपत्याभिधाने स्त्रीपुंलिङ्गस्याप्रसि-

द्विर्नपुंसकत्वात् । २५८९ सिद्धं तु प्रजनस्य विवक्षितत्वात् । २५९० एकार्थे शब्दान्यत्वाद् लिङ्गान्यत्वम् । २५९१ अवयवान्यत्वाच्च ॥

१ । ९३ एको गोत्रे १०९३ ॥ २५९२ उत्पादयितारं प्रत्यपत्ययोगात्तस्य च विवक्षितत्वादेकवचनं गोत्रे । २५९३ तत्र प्रत्ययान्ताद्गोत्रे प्रतिषेधो गोत्रे नियतत्वात् । २५९४ परमप्रकृतेश्चोत्पत्तिः । २५९५ स्त्रियां चानियमः । २५९६ यूनि चान्तर्हितेऽप्राप्तिः । २५९७ सर्वेषामपत्ययोगात्प्रत्ययान्ताद्गोत्रे प्रतिषेधार्थमेको गोत्रे । २५९८ नियमानुपपत्तिश्च । २५९९ न ह्येकस्मिन्नपत्येऽनेकप्रत्ययप्राप्तिः । २६०० अपत्यान्तरे शब्दान्तरात्प्रत्ययान्तरप्राप्तिः । २६०१ अपत्यं समुदायश्चेन्नियमोऽत्र समीक्षितः । २६०२ तस्मिन्सुबहवः प्राप्ता नियमोऽस्य भविष्यति ॥ २६०३ तस्मात्प्रतिषेधः । २६०४ संज्ञाकारिभ्यो वा प्रत्ययोत्पत्तिः । २६०५ गोत्राद्यूनीति च । २६०६ तच्च जात्यादिनिवृत्त्यर्थम् ॥

१ । ९५ अत इञ् १०९५ ॥ २६०७ इञो वृद्धावृद्धाभ्यां फिञ्फिनौ विप्रतिषेधेन । २६०८ तद्राजश्च ॥

१ । ९६ बाह्वादिभ्यश्च १०९६ ॥ २६०९ बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेधः । २६१० संबन्धिशब्दप्रत्ययानां तत्सदृशात्प्रतिषेधः ॥

१ । ९७ सुधातुरकङ् च १०९७ ॥ २६११ सुधातृव्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम् ॥

१ । १०४ अनृष्यानन्तर्ये बिदादिभ्योऽञ् ११०६ ॥ २६१२ अनृष्यानन्तर्यवचनमनर्थकं संज्ञागोत्राधिकारात् ॥

१ । ११४ ऋष्यन्धकवृष्णिकुरुभ्यश्च १११७ ॥ २६१३ ऋषिभ्यणो ढाक्कौ विप्रतिषेधेन । २६१४ द्व्यचो ढको ढ्रगढञौ । २६१५ न वर्ष्यणः पुनर्वचनमन्यानिवृत्त्यर्थम् । २६१६ तस्माद्वृष्णिभ्योऽण्विधानेऽत्र्यादिप्रतिषेधः । २६१७ ढकः पुनर्वचनमन्यनिवृत्त्यर्थम् । २६१८ तस्मात्तन्नामिकाण्यद्व्यचः । २६१९ ऋष्यन्धकवृष्णिकुर्वणः सेनान्ताण्ण्यः ॥

१ । १२० स्त्रीभ्यो ढक् ११२३ ॥ २६२० वडवाया वृषे वाच्ये । २६२१ अण् क्रुञ्चाकोकिलात्स्मृतः । २६२२ आरक् पुंसि ततोऽन्यत्र । २६२३ गोधाया ढ्रग्विधौ स्मृतः ॥

१ । १२८ चटकाया ऐरक् ११३५ ॥ २६२४ चटकायाः पुंलिङ्गनिर्देशः । २६२५ स्त्रियामपत्ये लुक् ॥

१ । १३० आरगुदीचाम् ११३६ ॥ २६२६ आरग्वचनमनर्थकं रका सिद्धत्वात् ॥

१ । १३७ राजश्वशुराद्यत् ११५३ ॥ २६२७ राज्ञोऽपत्ये जातिग्रहणम् ॥

१ । १४५ व्यन्सपत्ने ११६८ ॥ २६२८ व्यन्वचनमनर्थकं प्रत्ययार्थाभावात् ॥

१ । १४७ गोत्रस्त्रियाः कुत्सने ण च ११७१ ॥ २६२९ गोत्रस्त्रियाः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य । २६३० लुगर्थमिति चेन्न लुक्प्रतिषेधात् । २६३१ व्यवहितत्वादप्रतिषेधः । २६३२ व्यवहितत्वादप्रतिषेध इति चेन्न पुंवद्भावात् । २६३३ फिनर्थं तु २६३४ पुंवद्भावप्रतिषेधार्थं च । २६३५ गोत्राद्यून्यस्त्रियामिति वचनादप्रयोजनम् । २६३६ अवंश्यत्वाद्वा स्त्रियाः प्रयोजनम् ॥

१ । १५० फाण्टाहृतिमिमताभ्यां णफिञौ ११७४ ॥ २६३७ फाण्टाहृतेः प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य । २६३८ पुंवद्भावप्रतिषेधार्थं तु ॥

१ । १५१ कुर्वादिभ्यो ण्यः ११७५ ॥ २६३९ वामरथस्य कण्वादिवत्स्वरवर्जम् ॥

१ । १५३ उदीचामिञ् ११७७ ॥ २६४० उदीचामिञ्विधौ तक्ष्णोऽण्वचनम् । २६४१ शिवादिरिति चेण्ण्यविधिः । २६४२ सिद्धं तूदीचां वा ण्यवचनात् ॥

१ । १५५ कौशल्यकार्मार्याभ्यां च ११७९ ॥ २६४३ फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषाणां युट् च । २६४४ सिद्धं त्वादिष्टस्य युड्वचनात् ॥

१ । १५८ वाकिनादीनां कुक् च ११८२ ॥ २६४५ कुटि प्रत्ययादेरादेशानुपपत्तिरनादित्वात् । २६४६ पूर्वान्ते नलोपवचनम् । २६४७ सिद्धं त्वादिष्टस्य कुड्वचनात् । २६४८ कारिभ्य इञोऽगोत्रात्फिञ्विप्रतिषेधेन ॥

१ । १६१ मनोर्जातावञ्यतौ षुक् च ११८५ ॥ २६४९ अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिद्ध्यति माणवः ॥

१ । १६२ अपत्यं पौत्रप्रभृति गोत्रम् १०८९ ॥ २६५० पौत्रप्रभृतेर्गोत्रसंज्ञायां यस्यापत्यं तस्य पौत्रप्रभृतिसंज्ञाकरणम् । २६५१ जीवद्वंश्यं तु कुत्सितम् ॥

१ । १६३ जीवति तु वंश्ये युवा १०९० ॥ २६५२ जीवति तु वंश्ये युवेति पौत्रप्रभृत्यपेक्षं च । २६५३ तच्च देवदत्त्यर्थम् । २६५४ वृद्धस्य च पूजायाम् । २६५५ आपत्यो वा गोत्रम् । २६५६ परमप्रकृतेश्चापत्यः । २६५७ आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयो युवसंज्ञः । २६५८ स चास्त्रियाम् । २६५९ एको गोत्रग्रहणानर्थक्यं च । २६६० बहुवचनलोपिषु च सिद्धम् ॥

१ । १६५ वान्यस्मिन्सपिण्डे स्थविरतरे जीवति १०९२ ॥ २६६१ गोत्रयूनोः समावेशे को दोषस्तत्कृतं भवेत् । २६६२ यस्कादिषु न दोषोऽस्ति न यूनीत्यनुवर्तनात् ॥ २६६३ दोषोऽत्रिविदपञ्चाला न यूनीत्यनुवर्तनात् । २६६४ कण्वादिषु न दोषोऽस्ति न यून्यास्ति ततः परम् ॥ २६६५ एको गोत्रे प्रतिपदम् । २६६६ गोत्राद्यूनि च तत्स्मरेत् । २६६७ राजन्याद्वुञ्मनुष्याच्च ज्ञापकं लौकिकं परम् ॥

१ । १६८ जनपदशब्दात्क्षत्रियादञ् ११८६ ॥ २६६८ क्षत्रियादेकराजात्संघप्रतिषेधार्थम् । २६६९ क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् । २६७० पूरोरण्वक्तव्यः । २६७१ पाण्डोर्ड्यण्वक्तव्यः ॥

१ । १७० द्व्यञ्मगधकलिङ्गसूरमसादण् ११८८ ॥ २६७२ अणो ञ्यङ्ण्येञो विप्रतिषेधेन । २६७३ ञ्यङः कुरुनादिभ्यो ण्यः ॥

१ । १७५ कम्बोजाल्लुक् ११९४ ॥ २६७४ कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम् ॥

१ । १७७ अतश्च ११९६ ॥ २६७५ अत इति तदन्तग्रहणमवन्त्यादिभ्यो लुग्वचनात् । २६७६ पर्श्वादिभ्यो लुग्वक्तव्यः । २६७७ यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वादिलुकः ॥

२ । १ तेन रक्तं रागात् १२०२ ॥ २६७८ रक्तादीनामर्थाभिधाने प्रत्ययविधानादुपाध्यानर्थक्यम् ॥

२ । २ लाक्षारोचनाट्ठक् १२०३ ॥ २६७९ ठक्प्रकरणे शकलकर्दमाभ्यामुपसंख्यानम् । २६८० नील्या अन् । २६८१ पीतात्कन् । २६८२ हरिद्रामहारजनाभ्यामञ् ॥

२ । ३ नक्षत्रेण युक्तः कालः १२०४ ॥ २६८३ नक्षत्रेण चन्द्रमसो योगात्तद्युक्तात्काले प्रत्ययविधानम् । २६८४ तत्रोत्तरपदलोपः । २६८५ लिङ्गवचनानुपपत्तिश्च । २६८६ कालयोगात्सिद्धम् । २६८७ तथा च संप्रत्ययः ॥

२ । ७ दृष्टं साम १२०८ ॥ २६८८ दृष्टं साम कलेर्ढक् । २६८९ सर्वत्राग्निकलिभ्यां ढक् । २६९० दृष्टे सामनि जाते चाप्यण् डिद्विर्वा विधीयते । २६९१ तीयादीकक् । २६९२ न विद्यायाः । २६९३ गोत्रादङ्कवदिष्यते ॥

२ । १० परिवृतो रथः १२११ ॥ २६९४ परिवृतो रथ इति तदेकान्तग्रहणम् ॥

२ । १३ कौमारापूर्ववचने १२१४ ॥ २६९५ कौमारापूर्ववचन इत्युभयतः स्त्रिया अपूर्वत्वे । २६९६ कौमारापूर्ववचने कुमार्या अण्विधीयते । २६९७ अपूर्वत्वं यदा तस्याः कुमार्यां भवतीति वा ॥ २६९८ पुंयोगात्स्त्र्यभिधानम् ॥

१ । २१ सास्मिन्पौर्णमासीति संज्ञायाम् १२२३ ॥ २६९९ सास्मिन्पौर्णमासीति संज्ञाग्रहणम् । २७०० असंज्ञायां गरीयानुपसंयोगः ॥

२ । २८ छ च १२३० ॥ २७०१ छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम् । २७०२ शतरुद्राद्घ च ॥

२ । ३४ कालेभ्यो भववत् १२३७ ॥ २७०३ कालेभ्यो भवे प्रत्ययमात्रप्रसङ्गः । २७०४ यः कालेभ्यो भवे तस्य विधाने प्रातिपदिकमात्रात्प्रसङ्गः । २७०५ सिद्धं तूभयनिर्देशात् ॥

२ । ३५ महाराजप्रोष्ठपदाट्ठञ् १२३८ ॥ २७०६ ठञ्प्रकरणे तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् । २७०७ पूर्णमासादण् ॥

२ । ३६ पितृव्यमातुलमातामहपितामहाः १२४२ ॥ २७०८ पितृमातृभ्यां भ्रातरि व्यड्डुलचौ । २७०९ मातृपितृभ्यां पितरि डामहच् । २७१० मातरि षिच्च । २७११ महो वा छन्दस्यनञोऽवग्रहदर्शनात् । २७१२ अवेर्दुग्धे सोढदूसमरीसचः । २७१३ तिलान्निष्फलात्पिञ्जपेजौ । २७१४ पिञ्जश्छन्दसि डिच्च ॥

२ । ३८ भिक्षादिभ्योऽण् १२४४ ॥ २७१५ भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्प्रत्ययविधौ ॥

२ । ३९ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् १२४६ ॥ २७१६ वृद्धाच्चेति वक्तव्यम् । २७१७ अजो वुञ्पूर्वविप्रतिषिद्धम् । २७१८ ठक्तु विप्रतिषेधात् ॥

२ । ४० केदाराद्यञ्च १२४८ ॥ २७१९ गणिकायाश्चेति वक्तव्यम् ॥

२ । ४२ ब्राह्मणमाणववाडवाद्यत् १२५० ॥ २७२० यन्प्रकरणे पृष्ठादुपसंख्यानम् ॥

२ । ४३ ग्रामजनबन्धुभ्यस्तल् १२५१ ॥ २७२१ गजसहायाभ्यां चेति वक्तव्यम् । २७२२ अह्नः खः । २७२३ क्रतौ । २७२४ पर्श्वा णस् ॥

२ । ४५ खण्डिकादिभ्यश्च १२५४ ॥ २७२५ अञ्सिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात् । २७२६ गोत्राद्वुञ् न च तद्गोत्रम् । २७२७ तदन्तान्न स सर्वतः ॥ २७२८ ज्ञापकं स्यात्तदन्तत्वे । २७२९ तथा चापिशलेर्विधिः । २७३० सेनायां नियमार्थं वा । २७३१ तथा बाध्येत वाञ्वुञा ॥ २७३२ अञ्प्रकरणे क्षुद्रकमालवात्सेनासंज्ञायाम् ॥

२ । ४९ पाशादिभ्यो यः १२५८ ॥ २७३३ पृथग्वा तादर्शनादसमूहः । २७३४ शीघ्रत्वे तु ।

२ । ५०-५१ खलगोरथात् १२५९ । इनित्रकट्यचश्च १२६० ॥ २७३५ खलादिभ्य इनिः ॥

२ । ५२ विषयो देशे १२६१ ॥ २७३६ विषयाभिधाने जनपदे लुब्बहुवचनविषयात् । २७३७ गान्धार्यादिभ्यो वा । २७३८ राजन्यादिभ्यो वा वुञ् । २७३९ बैल्ववनादिभ्यो नित्यम् । २७४० न वाभिधेयस्य निवासविषयत्वान्निवासविवक्षायां लुब् विषयविवक्षायां प्रत्ययः ॥

२ । ५५ सोऽस्यादिरिति च्छन्दसः प्रगाथेषु १२६४ ॥ २७४१ छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ उपसंख्यानम् ॥

२ । ६० क्रतूक्थादिसूत्रान्ताट्ठक् १२७० ॥ २७४२ तस्येदंप्रत्ययाल्लुक् । २७४३ तस्येदंप्रत्ययस्य च । २७४४ विद्यालक्षणकल्पसूत्रान्तादकल्पादेरिकक् स्मृतः । २७४५ विद्या चानङ्गक्षत्रधर्मत्रिपूर्वा । २७४६ आख्यानाख्यायिकेतिहासपुराणेभ्यश्च । २७४७ अनुसूर्लक्ष्यलक्षणे च । २७४८ सर्वसादेर्द्विगोश्च लः । २७४९ इकन्पदोत्तरपदात् । २७५० शतषष्टेः षिकन्पथः ॥

२ । ६५ सूत्राच्च कोपधात् १२७७ ॥ २७५१ संख्याप्रकृतेरिति वक्तव्यम् ॥

२ । ६६ छन्दोब्राह्मणानि च तद्विषयाणि १२७८ ॥ २७५२ अन्यत्राभिधेयस्यानित्यत्वाच्छन्दोब्राह्मणानां तद्विषयवचनम् । २७५३ तत्र यथाधिकारं तद्विषयप्रसङ्गः । २७५४ सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात् । २७५५ याज्ञवल्क्यादिभ्यः प्रतिषेधः । २७५६ इनिर्वा प्रोक्ते तद्विषयः । २७५७ काश्यपकौशिकग्रहणं च कल्पे नियमार्थम् ॥

२ । ७१ औरञ् १२८३ ॥ २७५८ औरञ्विधेर्नद्यां मतुब्विप्रतिषिद्धम् ॥

२ । ८५ नद्यां मतुप् १३०४ ॥ २७५९ नद्यां मतुब्वचनं मत्वर्थेऽण्विधानात् । २७६० निर्वृत्ताद्यर्थं च ॥

२ । ८७ कुमुदनडवेतसेभ्यो ड्मतुप् १३०६ ॥ २७६१ महिषाच्चेति वक्तव्यम् ॥

२ । ९१ नडादीनां कुक्च १३१० ॥ २७६२ कुटि प्रत्ययादेरादेशानुपपत्तिरनादित्वात् । २७६३ पूर्वान्ते ह्रस्वत्वम् । २७६४ सिद्धं त्वादिष्टस्य कुङ्वचनात् । २७६५ संनियोगात्सिद्धम् ॥

२ । ९२ शेषे १३१२ ॥ २७६६ शेषवचनं घादीनामपत्यादिष्वप्रसङ्गार्थम् । २७६७ तस्येदंवचनात्प्रसङ्गः । २७६८ विप्रतिषेधात्सिद्धम् । २७६९ न वा परत्वाद्घादीनाम् । २७७० अणपवादत्वाच्चाण्विषये घादिप्रसङ्गः ॥

२ । ९३ राष्ट्रावारपाराद्घखौ १३१३ ॥ २७७१ अवारपाराद्विगृहीतादपि । २७७२ विपरीताच्च ॥

२ । ९५ कत्र्यादिभ्यो ढकञ् १३१५ ॥ २७७३ ग्रामाच्चेति वक्तव्यम् ॥

२ । ९६ कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु १३१६ ॥ २७७४ कुलस्यापत्यं कुक्षिग्रीवात्तु कन्ढञः ॥

२ । ९९ कापिश्याः ष्फक् १३१९ ॥ २७७५ बाह्ल्युर्दिपर्दिभ्यश्चेति वक्तव्यम् ॥

२ । १०० रङ्कोरमनुष्येऽण्च १३२० ॥ २७७६ रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोर्वुञ्विधानात् । २७७७ अमनुष्ये मनुष्यस्थे ष्फग्गणोऽज्ञापकमिति चेन्नानिष्टत्वात् । २७७८ अण्ग्रहणं च कच्छादिभ्योऽण्वचनात् ॥

२ । १०४ अव्ययात्त्यप् १३२४ ॥ २७७९ अमेहक्वतसित्रेभ्यस्त्यब्विधियोंऽव्ययात्स्मृत. २७८० त्यब्नेर्ध्रुवे । २७८१ निसो गते । २७८२ अरण्याण्ण्यः । २७८३ दूरादेत्यः । २७८४ उत्तरादाहञ् । २७८५ अव्ययात्त्यप्याविष्ट्यस्योपसंख्यानं छन्दसि । २७८६ अव्यय. तीररूप्योत्तरपदीच्यग्रामकोपधविधेर्वृद्धाच्छो विप्रतिषेधेन । २७८७ तेभ्यष्ठञ्ञिठौ । २७८८ न वा ठञादीनां छापवादत्वात्तद्विषये चाभावादितरेषाम् । २७८९ कोपधादणः पुनर्वचनमन्यनि. वृत्त्यर्थम् । २७९० तस्मादन्तोदात्ते कोपधप्रतिषेधः । २७९१ छादोदेंशे कालाट्ठञ् । २७९२ नक्षत्रादण् । २७९३ अव्ययाट्ट्युट्युलौ । २७९४ शरीरावयवाद्यत् । २७९५ वर्गान्ताच्छ. यत्खौ । २७९६ बह्वचोऽन्तोदात्ताट्ठञ् । २७९७ आयस्थानेभ्यष्ठक् । २७९८ विद्यायोनिसंबन्धेभ्यो वुञ् । २७९९ ऋतष्ठञ् । २८०० रूप्यमयटौ । २८०१ अचित्ताट्ठक् । २८०२ गोत्रक्षत्रिया. ख्येभ्यो बहुलं वुञ् । २८०३ गिनिरन्तेवासिब्राह्मणेभ्यः । २८०४ पञ्चपूर्वादञ् । २८०५ द्वन्द्व. द्वुन्वैरिमैथुनिकयोः । २८०६ गोत्रचरणाद्वुञ् । २८०७ कण्वादीञोऽण्विधेः । २८०८ ठञ्छि. भ्यामोर्देशे ठञ् । २८०९ न वा ठञोऽनवकाशत्वात् । २८१० योपधप्रस्थादीनां वुञ् । २८११ ओश्च ठञः । २८१२ जनपदानामकाणौ । २८१३ न वा वुञपवादत्वादणः । २८१४ कोपध. दणोऽकान्ताच्छः । २८१५ धन्ववुञश्च । २८१६ न वा छस्य पुनर्वचनं छापवादनिवृत्त्यर्थम्.

२ । १२४ जनपदतदवध्योश्च १३४८ ॥ २८१७ जनपदतदवध्योर्वुञ्विधानेऽनयवनाम्न्यप्रसङ्गः । २८१८ जनपदादिति चेद्वचनानर्थक्यम् ॥

२ । १२९ अरण्यान्मनुष्ये १३५३ ॥ २८१९ पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम् । २८२० वा गोमयेष्विति वक्तव्यम् ॥

२ । १३० विभाषा कुरुयुगंधराभ्याम् १३५४ ॥ २८२१ कुरुयुगंधरेभ्यो वावचनान्मनुष्यतत्स्थयोर्वुञ्विधानम् ॥

२ । १३३ कच्छादिभ्यश्च १३५७ ॥ २८२२ साल्वानां कच्छादिषु पाठोऽण्विधानार्थः । २८२३ न वा पदातिगोयवागूग्रहणमवधारणार्थम् ॥

२ । १३७ गर्त्तोत्तरपदाच्छः १३६१ ॥ २८२४ गर्त्तोत्तरपदाच्छविधेर्जनपदाद्वुञ्पूर्वविप्रतिषिद्धम् ॥

२ । १३८ गहादिभ्यश्च १३६२ ॥ २८२५ गहादिषु पृथिवीमध्यस्य मध्यमभावः । २८२६ चरणसंबन्धेन निवासलक्षणोऽण् ॥

२ । १४१ वृद्धादकेकान्तखोपधात् १३६५ ॥ २८२७ ईकान्तादपीति वक्तव्यम् । २८२८ अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम् ॥

३ । १ युष्मदस्मदोरन्यतरस्यां खञ्च १३७० ॥ २८२९ युष्मदस्मद्भ्यां प्रत्ययविधौ योगविभागः । २८३० समसंख्याप्रतिषेधार्थः ॥

३ । २ तस्मिन्नणि च युष्माकास्माकौ १३७१ ॥ २८३१ आदेशवचने च । २८३२ तत्र पुनः खञ्ग्रहणम् ॥

३ । ३ तवकममकावेकवचने १३७२ ॥ २८३३ एकार्थग्रहणं च ॥

३ । ४ अर्धाद्यत् १३७४ ॥ २८३४ अर्धाद्यद्विधाने सपूर्वाट्ठञ् । २८३५ दिक्पूर्वपदाद्यञ्च ।

३ । १९ श्वसस्तुट् च १३८९ ॥ २८३६ श्वसस्तुट्चादेशानुपपत्तिरनादित्वात् । २८३७ पूर्वान्ते तु प्रतिषेधः । २८३८ सिद्धं त्वादिष्टस्य तुड्वचनात् । २८३९ संनियोगाद्वा ॥

३ । २२ सर्वत्राण् च तलोपश्च १३९० ॥ २८४० हेमन्तस्याणि तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्तरत्वात् । २८४१ अलोपदर्शनाच्च ॥

३ । २३ सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च १३९१ ॥ २८४२ चिरपरुत्परारिभ्यस्त्नः । २८४३ प्रगस्य छन्दसि गलोपश्च । २८४४ अग्रादिपश्चाड्डिमच् । २८४५ अन्ताच्च । २८४६ सायचिरयोर्मकारान्तत्वं प्रत्ययसंनियुक्तम् । २८४७ सायमोऽह्ने मलोपः । २८४८ तरे च । २८४९ वा सप्तम्याम् । २८५० प्राह्णप्रगयोरेकारान्तत्वम् । २८५१ पूर्वान्ते विसर्जनीयः । २८५२ सिद्धं त्वादिष्टस्य तुड्वचनात् । २८५३ संनियोगाद्वा ॥

३ । २४ विभाषा पूर्वाह्णापराह्णाभ्याम् १३९२ ॥ २८५४ पूर्वाह्णापराह्णाभ्यां सुबन्तवचनं सप्तमीश्रवणार्थम् । २८५५ अलुग्वचनं ज्ञापकमिति चेदव्ययात्सप्तमीप्रसङ्गः ॥

३ । २५ तत्र जातः १३९३ ॥ २८५६ तत्र जातादिषु वचनं नियमार्थम् ॥

३ । ३४ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् १४०७ ॥ २८५७ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् । २८५८ फल्गुन्यषाढाभ्यां टानौ । २८५९ श्रविष्ठाषाढाभ्यां छण् । २८६० न वा नक्षत्रेभ्यो बहुलं लुग्वचनात् ।

३ । ३९ प्रायभवः १४१४ ॥ २८६१ प्रायभवग्रहणमनर्थकं तत्रभवेन कृतत्वात् । २८६२ अनित्यभवः प्रायभव इति चेन्मुक्तसंशयेन तुल्यम् ॥

३ । ४२ कोशाड्ढञ् १४१७ ॥ २८६३ विकारे कोशाड्ढञ् । २८६४ संभूते ह्यर्थानुपपत्तिः ॥

३ । ५३ तत्र भवः १४२८ ॥ २८६५ तत्रप्रकरणे तत्रेति पुनर्वचनं कालनिवृत्त्यर्थम् ॥

३ । ५८ गम्भीराञ्ञ्यः १४३५ ॥ २८६६ ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानम् ॥ २८६७ अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधः । (२८६८ 'बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्' इति काशिका)।

३ । ६० अन्तःपूर्वपदाट्ठञ् १४३७ ॥ २८६९ समानस्य तदादेश्च अध्यात्मादिषु चेष्यते । २८७० ऊर्ध्वं दमाच्च देहाच्च । २८७१ लोकोत्तरपदस्य च ॥ २८७२ मुखपार्श्वतसोरीयः । २८७३ कुग्जनस्य परस्य च । २८७४ ईयः कार्योऽथ मध्यस्य । २८७५ मण्मीयौ चापि प्रत्ययौ ॥ २८७६ मध्य मध्यं दिनण्चास्मात् । २८७७ स्थाम्नो लुगजिनात्तथा ॥

३ । ६६ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः १४४५ ॥ २८७८ भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः । २८७९ कृतनिर्देशौ हि तौ । २८८० तत्र व्याख्यातव्यनाम्नो ग्रहणं भवार्थम् । २८८१ व्याख्याने ह्यवचनात्सिद्धम् । २८८२ भवे मन्त्रेषु लुग्वचनम् । २८८३ कल्पे च व्याख्याने । २८८४ न वा तादर्थ्यात्ताच्छब्द्यम् ॥

३ । ७२ द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् १४५१ ॥ २८८५ नामाख्यातग्रहणं संघातविगृहीतार्थम् ॥

---

१. अत्र च 'बाह्यो दैव्यः पाञ्चजन्योऽथ गाम्भीराञ्ञ्य इष्यते' इति 'अन्तःपूर्व-' (४ । ३ । ६०) इति सूत्रस्थभाष्यं प्रमाणम् । दीक्षितेन तु दैव्यबाह्ययोर्वार्तिकान्तराभ्यामपि सिद्धत्वात्त्यक्त्वा 'पञ्चजनादुपसंख्यानम्' इत्येतावदेवोक्तम्.

३ । ८४ विदूराञ्ञ्यः १४६४ ॥ २८८६ वालवायो विदूरं च । २८८७ प्रकृत्यन्तरमेव वा । २८८८ नवै तत्रेति चेद्ब्रूयाज्जित्वरीवदुपाचरेत् ॥

३ । ८७ अधिकृत्य कृते ग्रन्थे १४६७ ॥ २८८९ अधिकृत्य कृते ग्रन्थे लुबाख्यायिकाभ्यो बहुलम् ॥

३ । ८८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः १४६८ ॥ २८९० द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ॥

३ । १०० जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने १४८० । २८९१ सर्ववचनं प्रकृतिनिर्ह्रासार्थम् । २८९२ तच्च मद्रवृज्यर्थम् ॥

३ । १०१ तेन प्रोक्तम् १४८१ ॥ २८९३ प्रोक्तग्रहणमनर्थकं तत्रादर्शनात् । २८९४ ग्रन्थे च दर्शनात् । २८९५ छन्दोऽर्थमिति चेत्तुल्यम् ॥

३ । १०४ कलापिवैशम्पायनान्तेवासिभ्यश्च १४८४ ॥ २८९६ प्रत्यक्षकारिग्रहणम् । २८९७ कलापिखाडायनग्रहणं ज्ञापकं वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य । २८९८ छन्दोग्रहणं चेतरथा ह्यतिप्रसङ्गः ॥

३ । १०५ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु १४८५ ॥ २८९९ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात् ॥

३ । ११६ कृते ग्रन्थे १४९६ ॥ २९०० कृते ग्रन्थे मक्षिकादिभ्योऽण् । २९०१ तद्विशेषेभ्यश्च । २९०२ योगविभागात्सिद्धम् ॥

३ । १२० तस्येदम् १५०० ॥ २९०३ तस्येदमित्यसंनिहितेऽप्राप्तिरिदमः प्रत्यक्षवाचित्वात् । २९०४ सिद्धं तु यद्योगा तत्र । २९०५ अनन्तरादिषु च प्रतिषेधः । २९०६ सिद्धं तु परिगणनात् । २९०७ स्वे ग्रामजनपदमनुष्येभ्यः । २९०८ पत्त्राद्वाह्ये । २९०९ रथाद्रथाङ्गे । २९१० वहेस्तुरणिट् च । २९११ अग्नीधः शरणे रञ् भं च । २९१२ समिधामाधाने षेण्यण् । २९१३ चरणाद्धर्माम्नाययोः ॥

३ । १२५ द्वन्द्वाद्वुन्वैरमैथुनिकयोः १५०५ ॥ २९१४ वैरे देवासुरादिभ्यः प्रतिषेधः ॥

३ । १२७ संघाङ्कलक्षणेष्वञ्यञिञामण् १५०७ ॥ २९१५ संघादिषु घोषग्रहणम् । २९१६ संघादिषु प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य । २९१७ लिङ्गपुंवद्भावप्रतिषेधार्थं तु ॥

३ । १३१ रैवतिकादिभ्यश्छः १५११ ॥ कौपिञ्जलहास्तिपदादण् । २९१८ आथर्वणिकस्येकलोपश्च ॥

३ । १३४ तस्य विकारः १५१४ ॥ २९१९ तस्यग्रहणे तस्य पुनर्वचनं शैषिकनिवृत्त्यर्थम् । २९२० तस्येदंवचनात्प्रसङ्गः । २९२१ बाधनार्थं कृतं भवेत् । २९२२ उत्सर्गः शेष एवासौ । २९२३ न वा संप्रत्ययः । २९२४ अवयवे च प्राण्योषधिवृक्षेभ्योऽनिवृत्तिः । २९२५ अणमयटोश्च विप्रतिषेधानुपपत्तिर्मयडुत्सर्गात् । २९२६ अनुवृत्तौ हि छस्योत्सर्गापवादविप्रतिषेधान्मयट् ॥

३ । १३६ बिल्वादिभ्योऽण् १५१६ ॥ २९२७ बिल्वादिषु गवेधुकाग्रहणं मयट्प्रतिषेधार्थम् ॥

३ । १४० अनुदात्तादेश्च १९२० ॥ २९२८ अनुदात्तादेरञो विधान आद्युदात्ता-न्ङीष उपसंख्यानम् । २९२९ पदस्य ह्यनुदात्तादित्वम् । २९३० न वा समर्थस्यानुदात्तादित्वात् । २९३१ पदग्रहणं परिमाणार्थम् ॥

३ । १४३ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः १९२३ ॥ २९३२ मयड्वैतयोर्वचनमपवादविषयेऽनिवृत्त्यर्थम् । २९३३ एतयोरित्यर्थनिर्देशः ॥

३ । १५५ ञितश्च तत्प्रत्ययात् १९३३ ॥ २९३४ विकारावयवयोर्विकारावयवयुक्तत्वान्मयट्प्रतिषेधार्थं ञितश्च प्रत्ययादञो विधानम् । २९३५ न वा वृद्धो ह्यवयव समुदायशब्दो विकारे च प्रकृतिशब्दस्तस्मान्मयडभावः । २९३६ विकारावयवशब्दात्प्रसङ्ग इति चेन्न तेनानभिधानात् । २९३७ अभिधाने ह्यन्यतोऽपि मयट्प्रसङ्गः । २९३८ तस्मात्तत्प्रत्ययान्ताल्लुग्वचनम् ॥

३ । १५६ क्रीतवत्परिमाणात् १९३४ ॥ २९३९ क्रीतवत्परिमाणादङ्गं च । २९४० अणो वृद्धान्मयट् । २९४१ ओरञोऽनुदात्तादेरञश्च । २९४२ मयटः प्राण्यञ्विप्रतिषेधेन । २९४३ न वानवकाशत्वादपवादो मयट् । २९४४ प्राण्यञश्च । २९४५ तस्मान्मयड्विधाने प्राणिप्रतिषेधः । २९४६ अनुदात्तादेरञः प्राण्यञ्विप्रतिषेधेन ॥

३ । १६३ फले लुक् १९४१ ॥ २९४७ फले लुग्वचनानर्थक्यं प्रकृत्यन्तरत्वात् । २९४८ एकान्तदर्शनात्प्रसङ्ग इति चेद्दृष्टे लुग्वचनम् ॥

३ । १६६ लुप् च १९४५ ॥ २९४९ लुप्प्रकरणे फलपाकशुषामुपसंख्यानम् । २९५० पुष्पमूलेषु च बहुलम् ॥

४ । १ प्राग्वहतेष्ठक् १९४८ ॥ २९५१ ठक्प्रकरणे तदाहेति माशब्दादिभ्य उपसंख्यानम् । २९५२ आहौ प्रभूतादिभ्यः । २९५३ पृच्छतौ सुस्नातादिभ्यः । २९५४ गच्छतौ परदारादिभ्यः ॥

४ । ९ आकर्षात्ष्ठल् १९५७ ॥ २९५५ आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥

४ । १७ विभाषा विवधात् १९६७ ॥ २९५६ वीवधाच्चेति वक्तव्यम् ॥

४ । २० क्त्रेर्मम्नित्यम् १९७० ॥ २९५७ त्रेर्मम्नित्यवचनं विषयार्थम् । २९५८ तत्र यथाधिकारं तद्विषयप्रसङ्गः । २९५९ भावप्रत्ययान्तादिमब्वक्तव्यः ॥

४ । २४ लवणाल्लुक् १९७४ ॥ २९६० लवणाल्लुग्वचनानर्थक्यं रसवाचित्वात् । २९६१ असंसृष्टे च दर्शनात् । २९६२ संसृष्टे चादर्शनात् ॥

४ । ३० प्रयच्छति गर्ह्यम् १९८० ॥ २९६३ प्रयच्छति गर्ह्याय । २९६४ मेस्यालोपो वा । २९६५ वृद्धेर्वृधुषिभावः ॥

४ । ४१ धर्मं चरति १९९१ ॥ २९६६ अधर्माच्च ॥

४ । ४९ ऋतोऽञ् १९९९ ॥ २९६७ नृनराभ्यामञ्वचनम् । २९६८ विशसितुरिड्लोपश्च । २९६९ विभाजयितुर्णिलोपश्च ॥

४ । ६५ हितं भक्षाः २०१६ ॥ २९७० हितं भक्षा इति चतुर्थीनिर्देशः । २९७१ इतरथा ह्यनिर्देशः ॥

४ । ७६ तद्वहति रथयुगप्रासङ्गम् १६२७ ॥ २९७२ वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययाविधानानर्थक्यं विहितत्वात् । २९७३ शब्दभेदादविधानम् । २९७४ शब्दभेदादविधानमिति चेदर्थाश्रयत्वात्प्रत्ययविधानस्यार्थसामान्यात्सिद्धम् ॥

४ । ८२ संज्ञायां जन्या १६३४ ॥ २९७५ जन्या इति निपातनानर्थक्यं पञ्चमीनिर्देशात् ॥

४ । ८३ विध्यत्यधनुषा १६३५ ॥ २९७६ विध्यत्यकरणेन । २९७७ इतरथा ह्यतिप्रसङ्गः ॥

४ । १२८ मत्वर्थे मासतन्वोः ३४७४ ॥ २९७८ मासतन्वोरनन्तरार्थे वा । २९७९ लुगकारेकाररेफाश्च ॥

४ । १४० वसोः समूहे च ३५८६ ॥ २९८० अक्षरसमूहे छन्दस उपसंख्यानम् । २९८१ छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् । २९८२ अग्नीरीशे वसव्यस्य । २९८३ स्वार्थविज्ञानात्सिद्धम् ॥

इति चतुर्थोऽध्यायः ।

पञ्चमोऽध्यायः ।

१ । २ उगवादिभ्यो यत् १६६२ ॥ २९८४ यञ्ज्यावञः पूर्वविप्रतिषिद्धं सनङ्गूपानहौ प्रयोजनम् । २९८५ ढञ्च । २९८६ हविरपूपादिभ्यो विभाषया यत् । २९८७ अन्नविकारेभ्यश्च । २९८८ नाभेर्नभभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात् । २९८९ सिद्धं तु शाखादिषु नभनाङ्गस्त्वं च । २९९० नभ्यात्तु लुग्वचनम् ॥

१ । ४ विभाषा हविरपूपादिभ्यः १६६४ ॥ २९९१ हविरपूपादिभ्योऽप्राप्ते ॥

१ । ६ शरीरावयवाच्च १६६६ ॥ २९९२ यत्प्रकरणे रथाच्च ॥

१ । ९ आत्मन्विश्वजनभोगोत्तरपदात्खः १६७० ॥ २९९३ भोगोत्तरपदात्खविधानेऽनिर्देशः पूर्वपदार्थहितत्वात् । २९९४ भोगीनरिति चेद्राव्वचनम् । २९९५ राजाचार्याभ्यां नित्यम् । २९९६ खविधाने पञ्चजनादुपसंख्यानम् । २९९७ सर्वजनाट्ठञ्च । २९९८ महाजनान्नित्यम् ॥

१ । १० सर्वपुरुषाभ्यां णढञौ १६७२ ॥ २९९९ सर्वाण्णस्य वावचनम् । ३००० पुरुषाद्वधविकारसमूहतेनकृतेषु ॥

१ । १२ तदर्थं विकृतेः प्रकृतौ १६७४ ॥ ३००१ तदर्थमिति कृत्यनामभ्यठञ् । ३००२ न वा प्रयोजनेन कृतत्वात् ॥

१ । १३ छदिरुपधिबलेर्ढञ् १६७५ ॥ ३००३ उपध्यर्थमिति प्रत्ययानुपपत्तिरुपध्यभावात् । ३००४ सिद्धं तु कृदन्तस्य स्वार्थेऽञ्वचनात् ॥

१ । १९ आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् १६८१ ॥ ३००५ ऊर्ध्वमानं किलोन्मानम् । ३००६ परिमाणं तु सर्वतः । ३००७ आयामस्तु प्रमाणं स्यात् । ३००८ संख्या बाह्या तु सर्वतः ॥ ३००९ भेदमात्रं ब्रवीत्येषा नैषा मानं कुतश्चन । ३०१० ठगादयः प्रागर्हादेदं तद्विधिः । ३०११ वस्नेवचनात्सिद्धम् । ३०१२ वस्नेवचनात्सिद्धमिति चेन्मांसौदनिकादिष्वप्राप्तिः । ३०१३ आर्हाच्चेद्भोजनादिष्वतिप्रसङ्गः ॥

१ । २० असमासे निष्कादिभ्यः १६८२ ॥ ३०१४ निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य । ३०१५ प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि ॥

१ । २१ शताच्च ठन्यतावशते १६८६ ॥ ३०१६ शतप्रतिषेधेऽन्यशतत्वे प्रतिषेधः ॥

१ । २२ संख्याया अतिशदन्तायाः कन् १६८७ ॥ ३०१७ तिग्रहणाड्तिग्रहणमिति चेदर्थवद्ग्रहणात्सिद्धम् ॥

१ । २५ कंसाट्टिठन् १६९० ॥ ३१०८ टिठन्नर्धाच्च । ३०१९ कार्षापणाद्वा प्रतिषेधश्च ॥

१ । २८ अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् १६९३ ॥ ३०२० संज्ञाप्रतिषेधानर्थक्यं च तन्निमित्तत्वाल्लोपस्य । ३०२१ उक्तं संख्यात्वे प्रयोजनं तस्मादिहाध्यर्धग्रहणानर्थक्यम् ॥

१ । २९ विभाषा कार्षापणसहस्राभ्याम् १६९४ ॥ ३०२२ कार्षापणसहस्राभ्यां सुवर्णशतमानयोरुपसंख्यानम् ॥

१ । ३०-३१ द्वित्रिपूर्वान्निष्कात् १६९५ । बिस्ताच्च १६९६ ॥ ३०२३ द्वित्रिभ्यां द्वैयोन्यम् । ३०२४ तत्र च बहुग्रहणम् ॥

१ । ३३ खार्या ईकन् १६९८ ॥ ३०२५ खार्या ईकन्केवलायाश्च । ३०२६ काकिण्याश्चोपसंख्यानम् । ३०२७ केवलायाश्च ॥

१ । ३५ शाणाद्वा १७०० ॥ ३०२८ शतशाणाभ्यां वा । ३०२९ द्वित्रिपूर्वादण्च ॥

१ । ३७ तेन क्रीतम् १७०२ ॥ ३०३० तेन क्रीतमिति करणात् । ३०३१ अकर्त्रेकान्तात् । ३०३२ संख्यैकवचनाद्द्विगोश्चोपसंख्यानम् ॥

१ । ३८ तस्य निमित्तं संयोगोत्पातौ १७०४ ॥ ३०३३ तस्य निमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् । ३०३४ संनिपाताच्च ॥

१ । ३९ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् १७०५ ॥ ३०३५ यत्प्रकरणे ब्रह्मवर्चसाच्च ॥

१ । ४७ तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते १७१३ ॥ ३०३६ तदस्मिन्दीयतेऽस्मा इति च ॥

१ । ४८ पूरणार्धाट्ठन् १७१४ ॥ ३०३७ ठन्प्रकरणेऽनन्तादुपसंख्यानम् ॥

१ । ५२ संभवत्यवहरतिपचति १७१८ ॥ ३०३८ तत्पचतीति द्रोणादण्च ॥

१ । ५७-५८ तदस्य परिमाणम् १७२३ ॥ संख्यायाः संज्ञासंघसूत्राध्ययनेषु १७२४ ॥ ३०३९ संज्ञायां स्वार्थे । ३०४० ततः परिमाणिनि । ३०४१ जीवितपरिमाणे चोपसंख्यानम् । ३०४२ जीवितपरिमाणे चेत्यनर्थकं वचनं कालादिति सिद्धत्वात् । ३०४३ इह वचने हि लुक्प्रसङ्गः । ३०४४ अन्येभ्योऽपि दृश्यते खारशताद्यर्थम् । ३०४५ स्तोमे डविधिः पञ्चदशाद्यर्थः ॥

१ । ५९ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् १७२५ ॥ ३०४६ विंशत्यादयो दशदर्थे चेत्समासवचनानुपपत्तिः । ३०४७ परिमाणिनि चेत्पुनः स्वार्थे प्रत्ययविधानम् । ३०४८ षष्ठीवचनविधिश्च । ३०४९ अनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषु ॥

१ । ६४-७६ छेदादिभ्यो नित्यम् १७२९ । पन्थो ण नित्यम् १७४० ॥ ३०५० छेदादिपथिभ्यो विग्रहदर्शनान्नित्यग्रहणानर्थक्यम् । ३०५१ विकारार्थमिति चेदकञादिभिस्तुल्यम् ॥

१।७१ यज्ञर्त्विग्भ्यां घखञौ १७३५ ॥ ३०५२ यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् ॥

१।७२ पारायणतुरायणचान्द्रायणं वर्तयति १७३६ ॥ ३०५३ तद्वर्तयतीत्यनिर्देशस्तत्त्वादर्शनात् । ३०५४ इड्यज्ज्योश्च दर्शनात् ॥

१।७४ योजनं गच्छति १७३८ ॥ ३०५५ योजनं गच्छतीति क्रोशशतयोजनशतयोरुपसंख्यानम् । ३०५६ ततोऽभिगमनमर्हतीति च ॥

१।७७ उत्तरपथेनाहृतं च १७४१ ॥ ३०५७ आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसंख्यानम् । ३०५८ अजपथशङ्कुपथाभ्यां च । ३०५९ मधुकमरिचयोरणस्थलात् ॥

१।८० तमधीष्टो भृतो भूतो भावी १७४४ ॥ ३०६० अधीष्टभृतयोर्द्वितीयानिर्देशोऽनर्थकस्तत्त्वादर्शनात् । ३०६१ सिद्धं तु चतुर्थीनिर्देशात् ॥

१।८४ अवयसि ठंश्च १७४८ ॥ ३०६२ अवयसि ठंश्चेत्यनन्तरस्यानुकर्षः ॥

१।९० षष्टिकाः षष्टिरात्रेण पच्यन्ते १७५६ ॥ ३०६३ षष्टिके संज्ञाग्रहणम् ॥

१।९४ तदस्य ब्रह्मचर्यम् १७५८ ॥ ३०६४ तदस्य ब्रह्मचर्यमिति महानाम्न्यादिभ्य उपसंख्यानम् । ३०६५ तच्चरतीति च । ३०६६ अवान्तरदीक्षादिभ्यो डिनिः । ३०६७ अष्टाचत्वारिंशतो ड्वुंश्च । ३०६८ चातुर्मास्यानां यलोपश्च । ३०६९ चतुर्मासाण्ण्यो यज्ञे तत्रभवे । ३०७० संज्ञायामण् ॥

१।९६ तत्र च दीयते भववत् १७६० ॥ ३०७१ कार्यग्रहणमनर्थकं तत्रभवेन कृतत्वात् ॥

१।९७ व्युष्टादिभ्योऽण् १७६१ ॥ ३०७२ अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम् ॥

१।१११ अनुप्रवचनादिभ्यश्छः १७७४ ॥ ३०७३ छप्रकरणे विशिपूरिपदिरुहिप्रकृतेरनात्सपूर्वपदादुपसंख्यानम् । ३०७४ स्वर्गादिभ्यो यत् । ३०७५ पुण्याहवाचनादिभ्यो लुक् ॥

१।११३ ऐकागारिकट् चौरे १७७६ ॥ ३०७६ एकागारान्निपातानर्थक्यं ठञ्प्रकरणात् ॥

१।११४ आकालिकडाद्यन्तवचने १७७७ ॥ ३०७७ आकालान्निपातनानर्थक्यं ठञ्प्रकरणात् । ३०७८ आकालाट्ठंश्च ॥

१।११९ तस्य भावस्त्वतलौ १७८१ ॥ ३०७९ स्त्रीपुंसाभ्यां त्वतलोरुपसंख्यानम् । ३०८० वावचनं च । ३०८१ अपवादसमावेशाद्वा सिद्धम् । ३०८२ तस्य भाव इत्यभिप्रायादिप्रतिप्रसङ्गः । ३०८३ सिद्धं तु यस्य गुणस्य भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ । ३०८४ यद्वा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भावस्तदभिधाने । ३०८५ त्वतल्भ्यां नञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थम् । ३०८६ वा छन्दसि । ३०८७ नञ्समासादन्यो भाववचनः स्वरोपपदवृद्ध्यर्थम् ॥

१।१२० आ च त्वात् १७८२ ॥ ३०८८ आ च त्वादिति चकारकरणमपवादसमावेशार्थम् ॥

१।१२१ न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः १७८३ ॥ ३०८९ न नञ्पूर्वादित्युत्तरस्य प्रतिषेधः ॥

१।१२२ पृथ्वादिभ्य इमनिज्वा १७८४ ॥ ३०९० पृथ्वादिभ्यो वावचनमण्समावेशार्थम् ॥

१।१२४ गुणवचनब्राह्मणादिभ्यः कर्मणि च १७८८ ॥ ३०९१ ब्राह्मणादिषु चातुर्वर्ण्यादीनामुपसंख्यानम् । ३०९२ अर्हतो नुम्च ॥

१ । १३० हायनान्तयुवादिभ्योऽण् १७९९ ॥ ३०९३ अण्प्रकरणे श्रोत्रियस्य घलोपश्च ॥
१ । १३२ योपधाद्गुरूपोत्तमाद्वुञ् १७९७ ॥ ('३०९४ सहायाद्वा' इति काशिका) ॥
२ । ४ विभाषा तिलमाषोमाभङ्गाणुभ्यः १८०५ ॥ ३०९५ तिलादिभ्यः खञ्च । ३०९६ उमाभङ्ग्योरधान्यत्वात् ॥

२ । ६ यथामुखसंमुखस्य दर्शनः खः १८०७ ॥ ३०९७ संमुखेति समस्यान्तलोपः ॥

२ । १० परोवरपरंपरपुत्रपौत्रमनुभवति १८११ ॥ ३०९८ परोवरेति परस्योत्ववचनम् । ३०९९ परपरतराणां परंपरभावः ॥

२ । १२ समांसमां विजायते १८१३ ॥ ३१०० समां समां विजायत इति यलोपवचनादलुग्विज्ञानम् । ३१०१ समां समां विजायत इति यलोपवचनादलुग्विज्ञानमिति चेदुत्तरपदस्य लुग्वचनम् । ३१०२ सिद्धं तु पूर्वपदस्य यलोपवचनात् । ३१०३ अनुत्पत्तावुत्तरपदस्य च वावचनम् ॥

२ । १४ आगवीनः १८१५ ॥ ३१०४ गोराङ्पूर्वादातस्य गोः प्रतिदानात्कारिणि खः ॥

२ । २३ हैयंगवीनं संज्ञायाम् १८२४ ॥ ३१०५ ह्योगोदोहस्य हियङ्ग्वादेशः संज्ञायां तस्य विकारे ॥

२ । २५ पक्षात्तिः १८२६ ॥ ३१०६ मूल इति वक्तव्यम् ॥

२ । २९ संप्रोदश्च कटच् १८३० ॥ ३१०७ कटच्प्रकरणे अलाबूतिलोमाभ्यो रजस्युपसंख्यानम् । ३१०८ भङ्गायाश्च । ३१०९ गोष्ठादयः स्थानादिषु पशुनामादिभ्यः । (३११० 'संघाते कटच् । ३१११ गुणादिभ्यो ग्रामच् । ३११२ कमलादिभ्यः षण्डच् । ३११३ नरकारितुरंगाणां स्कन्धच् । ३११४ पूर्वादिभ्यः काण्डच्' इति काशिका) । ३११५ विस्तारे पटच् । ३११६ द्वित्वे गोयुगच् । ३११७ ('षट्त्वे षड्गवच्' इति काशिका) । ३११८ विकारे स्नेहने तैलच् । ३११९ भवने क्षेत्रे शाकटशाकिनौ । ३१२० उपमानाद्वा सिद्धम् । (वार्तिकस्थादिपदग्राह्याः प्रत्यया भाष्यकाशिकयोर्दर्शिताः) ॥

२ । ३३ इनच्पिटच्चिकचि च १८३४ ॥ ३१२१ इनच्पिटच्काश्चिकचिचिकादेशाश्च ३१२२ क्लिन्नस्य चिल्पिलश्चास्य चक्षुषी । ३१२३ चुल् च वक्तव्यः ॥

२ । ३७ प्रमाणे द्वयसज्दघ्नञ्मात्रचः १८३८ ॥ ३१२४ प्रमाणं प्रत्ययार्थो न । ३१२५ तद्वति । ३१२६ अस्येति वर्तनात् । ३१२७ प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम । ३१२८ प्रमाणे लः । ३१२९ द्विगोर्नित्यम् । ३१३० डट् स्तोमे । ३१३१ शच्शनोर्डिनिः । ३१३२ विंशतेश्च । ३१३३ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये । ३१३४ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् ॥

२ । ३९ यत्तदेतेभ्यः परिमाणे वतुप् १८४० ॥ ३१३५ डावतावर्थवैशेष्यान्निर्देश पृथगुच्यते । ३१३६ मात्राद्यप्रतिघाताय । ३१३७ भावः सिद्धश्च डावतोः । ३१३८ वतुप्प्रकरणे युष्मदस्मद्भ्यां सादृश्य उपसंख्यानम् ॥

२ । ४२ संख्याया अवयवे तयप् १८४३ ॥ ३१३९ अवयवविधानेऽवयविनि प्रत्ययः ॥

२ । ४५ तदस्मिन्नधिकमिति दशान्ताड्डः १८४६ ॥ ३१४० अधिके समानजातौ ।

३१४१ इष्टं शतसहस्रयोः । ३१४२ यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम । ३१४३ डविधाने परिमाणशब्दानामाधिक्यस्याधिकरणाभावादनिर्देशः । ३१४४ सिद्धं तु पञ्चमीनिर्देशात् ॥

२ । ४६ शदन्तविंशतेश्च १८४७ ॥ ३१४५ शद्ग्रहणेऽन्तग्रहणं प्रत्ययग्रहणे यस्मात्स तदादेरधिकार्थम् । ३१४६ संख्याग्रहणं च । ३१४७ विंशतेश्च ॥

२ । ४७ संख्याया गुणस्य निमाने मयट् १८४८ ॥ ३१४८ निमाने गुणिनि । ३१४९ भूयसः । ३१५० एकोऽन्यतरः । ३१५१ समानानाम् । ३१५२ निमेये चापि दृश्यते ॥

२ । ४८ तस्य पूरणे डट् १८४९ ॥ ३१५३ तस्य पूरण इत्यतिप्रसङ्गः । ३१५४ सिद्धं तु संख्यापूरण इति वचनात् । ३१५५ यस्य वा भावादन्यसंख्यात्वं तत्र ॥

२ । ४९ नान्तादसंख्यादेर्मट् १८५० ॥ ३१५६ मडादिषु यस्यादिस्तन्निर्देशः । ३१५७ प्रत्ययान्तरे हि स्वरे दोषः ॥

२ । ५१ षट्कतिकतिपयचतुरां थुक् १८५१ ॥ ३१५८ चतुरश्छयतावाद्यक्षरलोपश्च । ३१५९ थट्थुकोः पृथक्करणं पदान्तविधिप्रतिषेधार्थम् ॥

२ । ५२ बहुपूगगणसंघस्य तिथुक् १८५२ ॥ ३१६० बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः । ३१६१ बहुकतिपयवतूनां लिङ्गविशिष्टादुत्पत्तिः सिद्धा । ३१६२ पुंवद्वचनं च ॥

२ । ५९ मतौ छः सूक्तसाम्नोः १८५९ ॥ ३१६३ छप्रकरणेऽनेकपदादपि । ३१६४ सिद्धं तु प्रातिपदिकविज्ञानात् । ३१६५ 'स्वं रूपं शब्दस्याशब्दसंज्ञा' इति वचनात् । ३१६६ आम्नायशब्दानामान्यभाव्यं स्वरवर्णानुपूर्वीदेशकालनियतत्वात् । ३१६७ पदैकदेशसुब्लोपदर्शनाच्च ॥

२ । ६० अध्यायानुवाकयोर्लुक् १८६० ॥ ३१६८ अध्यायानुवाकाभ्यां वा लुक् ॥

२ । ६९ धनहिरण्यात्कामे १८६९ ॥ ३१६९ धनहिरण्यात्कामाभिधाने । ३१७० षष्ठ्यर्थे ह्यनिष्टप्रसङ्गः ॥

२ । ७७ तावतिथं ग्रहणमिति लुग्वा १८७७ ॥ ३१७१ तावतिथं ग्रहणमिति लुग्वावचनानर्थक्यं विभाषाप्रकरणात् । ३१७२ तावतिथेन गृह्णातीति लुक्च ॥

२ । ७९ शृङ्खलमस्य बन्धनं करभे १८७९ ॥ ३१७३ शृङ्खलमस्य बन्धनं करभ इत्यनिर्देशः । ३१७४ सिद्धं तु तद्वन्निर्देशाल्लुक्च ॥

२ । ८२ तदस्मिन्नन्नं प्रायेण संज्ञायाम् १८८२ ॥ ३१७५ प्राये संज्ञायां वटकेभ्य इनिः ॥

२ । ८४ श्रोत्रियंश्छन्दोऽधीते १८८४ ॥ ३१७६ श्रोत्रियंश्छन्दोऽधीत इति वाक्यार्थे पदवचनम् । ३१७७ छन्दसो वा श्रोत्रभावस्तदधीत इति घंश्च ॥ ६ः

२ । ८५ श्राद्धमनेन भुक्तमिनिठनौ १८८५ ॥ ३१७८ इनिठनोः समानकालग्रहणम् ॥

२ । ९२ क्षेत्रियच्परक्षेत्रे चिकित्स्यः १८९२ ॥ ३१७९ क्षेत्रियः श्रोत्रियवत् । ३१८० परक्षेत्राद्वा तत्र चिकित्स्य इति परलोपो घंश्च ॥

२ । ९४ तदस्यास्त्यस्मिन्निति मतुप् १८९४ ॥ ३१८१ मतुप्प्रभृतयः सन्मात्रे चेदाते

प्रसङ्गः । ३१८२ तस्माद्भूमादिग्रहणम् । ३१८३ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ ३१८४ सन्मात्रे चर्षिदर्शनात् । ३१८५ गुणवचनेभ्यो मतुपो लुक् । ३१८६ अव्यतिरेकात्सिद्धमिति चेद्दृष्टो व्यतिरेकः । ३१८७ तथा च लिङ्गवचनसिद्धिः ॥

२ । ९५ रसादिभ्यश्च १८९९ ॥ ३१८८ रसादिभ्यः पुनर्वचनमन्यानिवृत्त्यर्थम् ॥

२ । ९६ प्राणिस्थादातो लजन्यतरस्याम् १९०३ ॥ ३१८९ प्राण्यङ्गादिति वक्तव्यम् ॥

२ । ९७ सिध्मादिभ्यश्च १९०४ ॥ ३१९० लजन्यतरस्यामिति समुच्चयः । ३१९१ पिच्छादिभ्यस्तुन्दादीनां नानायोगकरणं ज्ञापकमसमावेशस्य । ३१९२ वस्य पुनर्वचनं सर्वविभाषार्थम् ॥

२ । १०० लोमादिपामादिपिच्छादिभ्यः शनेलचः १९०७ ॥ ३१९३ नप्रकरणे दद्रु ह्रस्वत्वं च । ३१९४ विष्वगित्युत्तरपदलोपश्चाकृतसंधेः ॥

२ । १०१ प्रज्ञाश्रद्धार्चाभ्यो णः १९०८ ॥ ३१९५ वृत्तेश्च ॥

२ । १०२-१०३ तपःसहस्राभ्यां विनीनी १९०९ । अण् च १९१० ॥ ३१९६ तपसो विन्वचनमण्विधानात् । ३१९७ अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम् ॥

२ । १०७ ऊषशुषिमुष्कमधो रः १९१४ ॥ ३१९८ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् ॥ ('३१९९ नगपांसुपाण्डुभ्यश्च' इति काशिका) । ('३२०० कच्छ्वा ह्रस्वत्वं च' इति काशिका) ॥

२ । १०९ केशाद्वोऽन्यतरस्याम् १९१६ ॥ ३२०१ वप्रकरणे मणिहिरण्याभ्यामुपसंख्यानम् । ३२०२ छन्दसीवनिपौ च । ३२०३ मेधारथाभ्यामिरन्निरचौ ॥ ३२०४ वप्रकरणे अन्येभ्योऽपि दृश्यत इति वक्तव्यम् ॥

२ । ११२ रजःकृष्यासुतिपरिषदो वलच् १९१९ ॥ ३२०५ वलच्प्रकरणे अन्येभ्योऽपि दृश्यते ॥

२ । ११५ अत इनिठनौ १९२२ ॥ ३२०६ इनिठनोरेकाक्षरात्प्रतिषेधः । ३२०७ एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ ॥

२ । ११६ व्रीह्यादिभ्यश्च १९२३ ॥ ३२०८ शिखादिभ्य इनिर्वाच्य इकन्यवखदादिषु । ३२०९ शिखायवखदादिभ्यो नियमस्यावचनं निवर्तकत्वात् ॥

२ । १२० रूपादाहतप्रशंसयोर्यप् १९२७ ॥ ३२१० यप्प्रकरणे अन्येभ्योऽपि दृश्यते ॥

२ । १२२ बहुलं छन्दसि ३४९८ ॥ ३२११ छन्दोविन्प्रकरणे अष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्च । ३२१२ मर्मणश्चेति वक्तव्यम् । ३२१३ सर्वत्रामयस्य । ३२१४ शृङ्गवृन्दाभ्यामारकन् । ३२१५ फलबर्हाभ्यामिनच् । ३२१६ हृदयाच्चालुरन्यतरस्याम् । ३२१७ शीतोष्णतृप्रेभ्यस्तन्न सहते । ३२१८ हिमाच्चेलुः । ३२१९ बलाच्चोलः । ३२२० वातात्समूहे च । ३२२१ पर्वमरुद्भ्यां तप् । ३२२२ ददातिवृत्तं वा ॥

२ । १२५ आलजाटचौ बहुभाषिणि १९३२ ॥ ३२२३ कुत्सित इति वक्तव्यम् ॥

२ । १२९ वातातीसाराभ्यां कुक्च १९३६ ॥ ३२२४ पिशाचाच्चेति वक्तव्यम् ॥

२ । १३५ पुष्करादिभ्यो देशे १९४२ ॥ ३२२५ इनिप्रकरणे बलाद्बाहूरुपूर्वपदादुपसंख्यानम् । ३२२६ सर्वादेश्च । ३२२७ अर्थाच्चासंनिहिते । ३२२८ तदन्ताच्च ॥

३ । १ प्राग्दिशो विभक्तिः १९४७ ॥ ३२२९ विभक्तित्वे प्रयोजनमित्यातिषेधः । ३२३० इदमो विभक्तिस्वरश्च । ३२३१ त्यदादिविधयश्च ॥

३ । २ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः १९४८ ॥ ३२३२ बहुग्रहणे संख्याग्रहणम् । ३२३३ द्व्यादिप्रतिषेधात्किम उपसंख्यानम् ॥

३ । ५ एतदोऽन् १९५१ ॥ ३२३४ एतद इति योगविभागः । ३२३५ एतदश्च थम उपसंख्यानम् ॥

३ । ७-१० पञ्चम्यास्तसिल् १९५३ । सप्तम्यास्त्रल् १९५७ ॥ ३२३६ तसिलादयो विभक्त्यादेशाश्चेत्सुब्लुक्स्वरगुणदीर्घत्त्वौत्त्वस्मायादिविधिप्रतिषेधः । ३२३७ पञ्चमीनिर्देशात्सिद्धम् । ३२३८ अनादेशे स्वार्थविज्ञानात्समानशब्दाप्रतिषेधः ॥

३ । ८ तसेश्च १९५५ ॥ ३२३९ तसेस्तसिल्वचनं स्वरार्थम् ॥

३ । ९ पर्यभिभ्यां च १९५६ ॥ ३२४० पर्यभिभ्यां च सर्वोभयार्थे ॥

३ । १४ इतराभ्योऽपि दृश्यन्ते १९६३ ॥ ३२४१ भवदादियोग इति वक्तव्यम् ॥

३ । १८ दानीं च १९६७ ॥ ३२४२ दानीमिति निपातनात्स्वरसिद्धिः ॥

३ । १९ तदो दा च १९६८ ॥ ३२४३ तदो दावचनमनर्थकं विहितत्वात् ॥

३ । २० तयोर्दार्हिलौ च च्छन्दसि ३४१९ ॥ ३२४४ तयोरिति प्रातिपदिकनिर्देशः ॥

३ । २२ सद्यःपरुत्परार्यैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः १९७० ॥ ३२४५ समानस्य सभावो द्यश्चाहनि । ३२४६ पूर्वपूर्वतरयोः परभाव उदारी च संवत्सरे । ३२४७ इदमः समसण् । ३२४८ परस्मादेद्यव्यहनि । ३२४९ इदमोऽश्भावो द्यश्च । ३२५० पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युसुच् । ३२५१ द्युश्चोभयात् ॥

३ । ३१ उपर्युपरिष्टात् १९८१ ॥ ३२५२ ऊर्ध्वस्योपभावो रिल्रिष्टातिलौ च ॥

३ । ३२ पश्चात् १९८२ ॥ ३२५३ अपरस्य पश्चभाव आतिश्च प्रत्ययः । ३२५४ दिक्पूर्वपदस्य च । ३२५५ अर्धोत्तरपदस्य च समासे । ३२५६ अर्धे च ॥

३ । ३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः १९८४ ॥ ३२५७ अपञ्चम्या इति प्रागसः ॥

३ । ४२ संख्याया विधार्थे धा १९८८ ॥ ३२५८ धाविधानं धात्वर्थपृथग्भावे ॥

३ । ४४ एकाद्धो ध्यमुञन्यतरस्याम् १९९० ॥ ३२५९ सहभावे ध्यमुञ् ॥

३ । ४५ द्वित्र्योश्च धमुञ् १९९१ ॥ ३२६० धमुञन्तात्स्वार्थे डविधानम् ॥

३ । ४७ याप्ये पाशप् १९९३ ॥ ३२६१ पाशपि कुत्सितग्रहणम् ॥

३ । ५२ एकादाकिनिच्चासहाये १९९८ ॥ ३२६२ एकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानम् । ३२६३ सिद्धं तु संख्यादेशवचनात् । ३२६४ असहायस्य वा ॥

३ । ५५ अतिशायने तमबिष्ठनौ २००१ ॥ ३२६५ शुक्लतरस्य शुक्लभावात्प्रकृतेः प्रत्ययविज्ञानम् । ३२६६ तदन्ताच्च स्वार्थे छन्दसि दर्शनं श्रेष्ठतमायेति ॥

३ । ५७ द्विवचनविभज्योपपदे तरबीयसुनौ २००५ ॥ ३२६७ तरबीयसुनोरेकद्रव्यस्योत्कर्षापकर्षयोरुपसंख्यानम् । ३२६८ सिद्धं तु गुणप्रधानत्वात् ॥

३ । ६६ प्रशंसायां रूपप् २०२१ ॥ ३२६९ प्रकृतेर्लिङ्गवचनाभावात्तिङ्प्रकृतेरम्भावव-चनम् । ३२७० सिद्धं तु क्रियाप्रधानत्वात् । ३२७१ वृषलादिभ्य उपसंख्यानम् । ३२७२ सिद्धं तु प्रकृत्यर्थवैस्पष्ट्यवचनात् ॥

३ । ६७ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः २०२२ ॥ ३२७३ ईषदसमाप्तौ क्रियाप्रधा-नत्वाल्लिङ्गवचनानुपपत्तिः । ३२७४ प्रकृत्यर्थविशेषणत्वात्सिद्धम् । ३२७५ प्रकृत्यर्थे चेल्लिङ्गव-चनानुपपत्तिः । ३२७६ सिद्धं तु तत्संबन्ध उत्तरपदार्थे प्रत्ययवचनात् । ३२७७ क्तान्तात्प्र-त्ययविधानानुपपत्तिः क्तस्य भूतकाललक्षणत्वात्कल्पबादीनां चासमाप्तिवचनात् । ३२७८ सिद्धं त्वाशंसायां भूतवद्वचनात् ॥

३ । ६८ विभाषा सुपो बहुच्पुरस्तात्तु २०२३ ॥ ३२७९ बहुचि सुब्ग्रहणात्पूर्वत्र तिङो विधानम् । ३२८० स्वरः प्रातिपदिकत्वात् । ३२८१ तुग्रहणं नित्यपूर्वार्थम् । ३२८२ तमादिभ्य-कल्पादयो विप्रतिषेधेन । ३२८३ तमादिरीषत्प्रधानात् ॥

३ । ७१-७२ अव्ययसर्वनाम्नामकच्प्राक्टेः २०२६ । कस्य च दः २०२७ ॥ ३२८४ अनोकारसकारमकारादाविति वक्तव्यम् । ३२८५ अकच्प्रकरणे तूष्णीमः काम् । ३२८६ शीले को मलोपश्च । ३२८७ अम्बहुजकक्षु नानादेशत्वादुत्सर्गप्रतिषेधः । ३२८८ कविधेस्तमादयः पूर्वविप्रतिषिद्धम् । ३२८९ कदाचित्क्ष्निकतरादयः । ३२९० एकदेशिप्रधाः नञ्च समासः । ३२९१ उत्तरपदार्थप्रधानश्च संज्ञायां कन्विध्यर्थम् । ३२९२ कदाचिद्द्वन्द्वः ॥

३ । ७४ कुत्सिते २०२९ ॥ ३२९३ कुत्सितादीनामर्थे चेल्लिङ्गवचनानुपपत्तिः । ३२९४ कुत्सितादिसमानाधिकरणादिति चेदतिप्रसङ्गो यथा टाबादिषु । ३२९५ सिद्धं तु येन कुत्सि-तादिवचनं तद्युक्तात्स्वार्थे प्रत्ययविधानात् ॥

३ । ८३ ठाजादावूर्ध्वं द्वितीयादचः २०३५ ॥ ३२९६ चतुर्थात् । ३२९७ अनजादौ च । ३२९८ लोपः पूर्वपदस्य च । ३२९९ अप्रत्यये तथैवेष्टः । ३३०० उवर्णाल्ल इलस्य च । ३३०१ ठग्रहणमुक्तो द्वितीयत्वे कविधानार्थम् । ३३०२ अजादिलक्षणे हि माथितिकादिव-त्प्रसङ्गः । ३३०३ द्वितीयादचो लोपे संध्यक्षराद्द्वितीयत्वे तदादेर्लोपवचनम् ॥

३ । ८४ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् २०३८ ॥ ३३०४ वरुणादीनां च तृतीयात्स चाकृतसंधीनाम् । ३३०५ वाचिकादिषु पदवृत्तप्रतिषेधः । ३३०६ सिद्धमेकाक्ष-रपूर्वपदानामुत्तरपदलोपवचनात् । ३३०७ षषष्ठाजादिवचनात्सिद्धम् ॥

३ । ८८ कुटीशमीशुण्डाभ्यो रः २०४३ ॥ ३३०८ कुटीशमीशुण्डाभ्यः प्रत्ययसंनियो-गेन पुंवद्वचनम् ॥

३ । ९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे २०४६ ॥ ३३०९ वत्सादिभ्यस्तनुत्वे कार्श्ये-प्रतिषेधः ॥

३ । ९२-९३ किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् २०४७ । वा बहूनां जाति-परिप्रश्ने डतमच् २०४८ ॥ ३३१० किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम् ॥

३ । ९४ एकाच्च प्राचाम् २०४९ ॥ ३३११ प्राग्वचनानर्थक्यं च विभाषाप्रकरणात् ॥

३ । ९८ लुबमनुष्ये २०५३ ॥ ३३१२ लिङ्गसिद्ध्यर्थं लुबमनुष्ये ॥

३ । ११८ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् २०७१ ॥ ३३१३ अणो गोत्राद्गोत्रवचनम् ॥

४ । १ पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च २०७३ ॥ ३३१४ पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् ॥

४ । ३ स्थूलादिभ्यः प्रकारवचने कन् २०७५ ॥ ३३१५ कन्प्रकरणे चञ्चद्बृहतोरुपसंख्यानम् ॥

४ । ४ अनत्यन्तगतौ क्तात् २०७६ ॥ ३३१६ अनत्यन्तगतौ क्तान्तात्तमादयः पूर्वविप्रतिषिद्धम् । ३३१७ तदन्ताच्च स्वार्थे कन्वचनम् ॥

४।५ न सामिवचने २०७७ ॥ ३३१८ सामिवचने प्रतिषेधानर्थक्यं प्रकृत्याभिहितत्वात् ॥

४ । ७ अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः २०७९ ॥ ३३१९ अध्युत्तरपदात्प्रत्ययविधानानुपपत्तिर्विग्रहाभावात् । ३३२० तस्मात्तत्रेदमिति सधीनर् ॥

४ । २७ देवात्तल् २०९५ ॥ ३३२१ तलि स्त्रीलिङ्गवचनम् ॥

४ । ३० लोहितान्मणौ २०९८ ॥ ३३२२ लोहिताल्लिङ्गबाधनं वा । ३३२३ अक्षरसमूहे छन्दस्युपसंख्यानम् । ३३२४ छन्दसि बहुभिर्वसव्यैरुपसंख्यानम् । ३३२५ अग्नीशे वसव्यस्येति । ३३२६ अपऔक्कविक्षेमवर्चोनिष्केनलोकथजनपूर्वनवयविष्ठेभ्यो यत् । ३३२७ नवस्य नू त्नतनखाश्च । ३३२८ नश्च पुराणे प्रात् ॥

४ । ३६ तद्युक्तात्कर्मणोऽण् २१०४ ॥ ३३२९ अण्प्रकरणे कुलालवरुडनिषादचण्डालमित्रेभ्यश्छन्दसि । ३३३० भागरूपनामभ्यो धेयः । ३३३१ मित्राच्छन्दसि । ३३३२ अणामित्राच्च । ३३३३ सांनाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवादिवस्कृताग्रायणाग्रहायणसांतपनानि । ३३३४ आग्नीध्रसाधारणादञ् । ३३३५ अवयसमरुद्भ्यां छन्दसि । ३३३६ नवसूरमर्तयविष्ठेभ्यो यत् । ३३३७ क्षेमाद्यः ॥

४ । ४२ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् २१०९ ॥ ३३३८ बह्वल्पार्थान्मङ्गलामङ्गलवचनम् ॥

४ । ४४ प्रतियोगे पञ्चम्यास्तसिः २१११ ॥ ३३३९ तसिप्रकरण आद्यादिभ्य उपसंख्यानम् ॥

४ । ५० अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः २११७ ॥ ३३४० च्विविधावभूततद्भावग्रहणम् । ३३४१ प्रकृतिविवक्षाग्रहणं च । ३३४२ समीपादिभ्य उपसंख्यानम् ।

४ । ५७ अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् २१२८ ॥ ३३४३ डाचि त्रिरुक्तरणं विशेषणार्थम् ॥

४ । ६७ मद्रात्परिवापणे २१३८ ॥ ३३४४ भद्राच्चेति वक्तव्यम् ॥

४ । ६८ समासान्ताः ६७६ ॥ ३३४५ प्रयोजनमव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः ।

४ । ६९ न पूजनात् ९५४ ॥ ३३४६ पूजायां स्वतिग्रहणम् । ३३४७ प्राग्बहुव्रीहिग्रहणं च ।

४ । ७३ बहुव्रीहौ संख्येये डजबहुगणात् ८५१ ॥ ३३४८ डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं निस्त्रिंशाद्यर्थम् । ३३४९ अन्यत्राधिकलोपात् । ३३५० अव्ययादेरिति वक्तव्यम् ॥

४ । ७७ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ९४५ ॥ ३३५१ चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानम् ॥

४ । ७८ ब्रह्महस्तिभ्यां वर्चसः ९४६ ॥ ३३५२ पल्यराजभ्यां चेति वक्तव्यम् ॥

४ । ८७ अहःसर्वैकदेशसंख्यातपुण्याच्च रात्रेः ७८७ ॥ ३३५३ अहर्ग्रहणं द्वन्द्वार्थम् । ३३५४ तत्पुरुषाभावात् ॥

४ । ८८ अह्नोऽह्न एतेभ्यः ७९० ॥ ३३५५ अह्नोऽह्नवचनानर्थक्यं चाह्नष्टखोर्नियमवचनात् ॥

४ । १०३ अनसन्ताच्छन्दसि ३५०५ ॥ ३३५६ अनसन्तान्नपुंसकाच्छन्दसि वेति वक्तव्यम् ॥

४ । ११३ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् ८५२ ॥ ३३५७ षचि प्रत्ययान्तरकरणमन्तोदात्तार्थम् ॥

४ । ११५ द्वित्रिभ्यां ष मूर्ध्नः ८५४ ॥ ३३५८ मूर्ध्नः षवचनम् ॥

४ । ११६ अप्पूरणीप्रमाण्योः ८३२ ॥ ३३५९ अपि प्रधानपूरणीग्रहणम् । ३३६० नेतुर्नक्षत्र उपसंख्यानम् । ३३६१ छन्दसि च । ३३६२ मासाद्भृतिप्रत्ययपूर्वपदाट्ठज्विधिः ॥

४ । ११८ अञ्नासिकायाः संज्ञायां नसं चास्थूलात् ८५६ ॥ ३३६३ खरखुराभ्यां च नस्वक्तव्यः । ३३६४ शितिना अर्चना अहिना इति नैगमाः ॥

४ । ११९ उपसर्गाच्च ८५८ ॥ ३३६५ वेर्ग्रो वक्तव्यः । ३३६६ ख्यश्च ॥

४ । १३१ ऊधसोऽनङ् ४८३ ॥ ३३६७ ऊधसोऽनङि स्त्रीग्रहणम् ॥

४ । १३५ गन्धस्येदुत्पूतिसुसुरभिभ्यः ८७४ ॥ ३३६८ गन्धस्येत्त्वे तदेकान्तग्रहणम् ॥

४ । १५६ ईयसश्च ८९४ ॥ ३३६९ ईयस उपसर्जनदीर्घत्वं च । ३३७० पुंवद्वचनात्सिद्धम् ॥

इति पञ्चमोऽध्यायः ।

षष्ठोऽध्यायः ।

१ । १ एकाचो द्वे प्रथमस्य २१७९ ॥ ३३७१ एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देशः । ३३७२ एकवर्णेषु व्यपदेशिवद्वचनात् । ३३७३ प्रथमत्वे च । ३३७४ योगविभागो वा । ३३७५ एकाज्मात्रस्य द्विर्वचनार्थः । ३३७६ एकाचोऽवयवैकाच्त्वादवयवानां द्विर्वचनप्रसङ्गः । ३३७७ तत्र जुस्भाववचनम् । ३३७८ स्वरश्च । ३३७९ अड्भावश्च । ३३८० नुम्प्रतिषेधश्च । ३३८१ श्नसलहानिश्च । ३३८२ सिद्धं तु तत्समुदायैकाच्त्वाच्छास्त्रहानेः । ३३८३ तत्र बहुव्रीहिनिर्देशेऽनच्कस्य द्विर्वचनमन्यपदार्थत्वात् । ३३८४ सिद्धं तु तद्गुणसंविज्ञानात्पाणिनेर्यथा लोके । ३३८५ स्थाने द्विर्वचनं णिलोपवचनं समुदायादेशत्वात् । ३३८६ यच्च सन्यङन्तस्य द्विर्वचने । ३३८७ द्विष्प्रयोग इति चेण्णकारषकारादेशादेरुत्ववचनं लिटि । ३३८८ इड्वचनं च यङो । ३३८९ इदुद्गुणनिषेधश्च । ३३९० पदादिप्रतिषेधश्च ॥

१। २ अजादेर्द्वितीयस्य २१७६॥३३९१ द्वितीयस्येत्यवचनमजादेरिति कर्मधारयात्सप्तमी। ३३९२ द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात् । ३३९३ न वा प्रथमविज्ञाने हि द्वितीयाभा-सिरद्वितीयत्वात् । ३३९४ यथा वादिविकारेऽलोऽन्त्यविकाराभावः । ३३९५ तत्र पूर्वस्याचो निवृत्तौ व्यञ्जनानिवृत्तिरशासनात्पूर्वस्य । ३३९६ न्द्रादिप्रतिषेधाच्च । ३३९७ तत्र द्वितीयाभावे प्रथमाद्विर्वचनं प्रतिषिद्धत्वात् । ३३९८ सति तस्मिन्प्रतिषेधः । ३३९९ सति तस्मिन्प्रतिषेध इति चेद्धलादिशेषे दोषः । ३४०० लोकवद्धलादिशेषे । ३४०१ क्वचिदन्यत्र लोप इति चेद्द्विर्वचनम् ॥

१ । ३ न न्द्राः संयोगादयः २४४६ ॥ ३४०२ न्द्रादेर्द्विर्वचनप्रसङ्गस्तत्र न्द्राणां प्रतिषेधः ३४०३ ईर्ष्यतेस्तृतीयस्य । ३४०४ कण्ड्वादीनां च । ३४०५ वा नामधातूनाम् । ३४०६ यथेष्टं वा नामधातूनाम् ॥

१ । ५ उभे अभ्यस्तम् ४२६ ॥ ३४०७ अभ्यस्तसंज्ञायां सहवचनम् । ३४०८ आद्युदात्तत्वे पृथगप्रसङ्गार्थम् ॥

१ । ६ जक्षित्यादयः षट् ४२८ ॥ ३४०९ जक्षित्यादिषु सप्तग्रहणं वेवीत्यर्थम् । ३४१० अपरिगणनं वागणान्तत्वात् ॥

१ । ७ तुजादीनां दीर्घोऽभ्यासस्य ३५०९ ॥ ३४११ तुजादिषु छन्दःप्रत्ययग्रहणम् । ३४१२ अनारम्भो वापरिगणितत्वात् । ३४१३ अन्येषां च दर्शनात् । ३४१४ अनेकान्तत्वाच्च ॥

१ । ८ लिटि धातोरनभ्यासस्य २१७७ ॥ ३४१५ लिटि द्विर्वचने जागर्तेर्वावचनम् । ३४१६ अभ्यासप्रतिषेधानर्थक्यं च छन्दसि वावचनात् । ३४१७ प्रयोजनमादित्यान्याचिख्यासेह ॥

१ । ९ सन्यङोः २३९५ ॥ ३४१८ सन्यङोः परत इति चेदिटो द्विर्वचनं परादित्वात् । ३४१९ हन्तेश्चेटः । ३४२० एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्सन इट्प्रतिषेधः । ३४२१ सन्यङन्तस्येति चेदशः सन्यनिटः । ३४२२ दीर्घकुत्वप्रसारणषत्वमाधि-कस्य द्विर्वचनात् । ३४२३ आवृद्धचोश्चाभ्यस्तविधिप्रतिषेधः । ३४२४ सङाश्रये च समुदायस्य समुदायदेशत्वाज्झलाश्रये चाव्यपदेश आमिश्रत्वात् ॥

१ । १२ दाश्वान्साह्वान्मीढ्वांश्च ३६२९ ॥ ३४२५ दाशेर्वसौ द्वित्वेट्प्रतिषेधौ । ३४२६ सहेर्दीर्घत्वं च । ३४२७ मिहेर्ढत्वं च । ३४२८ मह्यर्थ इति चेन्मिहेस्तदर्थत्वात्सिद्धम् । ३४२९ द्विर्वचनप्रकरणे कृञादीनां के । ३४३० चरिचलिपतिपदिवदीनामच्याक्चाभ्यासस्य । ३४३१ हन्तेर्घनः । ३४३२ पाटेर्णिलुक्च दीर्घश्चाभ्यासस्योक्च । ३४३३ द्विर्वचनं यणयवायावादेशाल्लो-पोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः । ३४३४ द्विर्वचनात्प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वे-त्त्वोत्त्वगुणवृद्धिविधयः ॥

१ । १३ ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे १००३ ॥ ३४३५ ष्यङः संप्रसारणे पुत्रपत्योस्तदादावतिप्रसङ्गः । ३४३६ वर्णग्रहण इति चेत्तदन्तप्रतिषेधः । ३४३७ सिद्धं तू-त्तरपदवचनात् । ३४३८ यथागृहीतस्यादेशवचनादप्रत्ययस्थे सिद्धम् । ३४३९ अनन्त्य-विकारेऽन्त्यसदेशस्य वा । ३४४० प्रयोजनं न संप्रसारणे संप्रसारणम् । ३४४१ सान्तम-हतोर्दीर्घत्वे । ३४४२ अन्कारान्तस्याल्लोपे । ३४४३ मृजेर्वृद्धिविधौ । ३४४४ वसोः संप्रसारणे

च । ३४४५ युवादीनां च । ३४४६ वोरुपधाग्रहणं च । ३४४७ आदित्यदादिविधिसंयोगादिलो-पकुत्वढत्वभष्भावपत्वणत्वेष्वतिप्रसङ्गः । ३४४८ उदात्तनिर्देशात्सिद्धम् ॥

१ । १४ बन्धुनि बहुव्रीहौ १००५ ॥ ३४४९ मातज्मातृकमातृषु व्यङ् प्रसार्यो विभाषया ॥

१ । १६ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च २४१२ ॥ ३४५० वयिग्रहणं वेञः प्रतिषेधात् । ३४५१ न वा यकारप्रतिषेधो ज्ञापकोऽप्रतिषेधस्य । ३४५२ पित्यभ्यासार्थमिति चेन्नाविशिष्टत्वात् ॥

१ । १७ लिट्यभ्यासस्योभयेषाम् २४०८ ॥ ३४५३ अभ्याससंप्रसारणं हलादिशेषा-द्विप्रतिषेधेन । ३४५४ न वा संप्रसारणाश्रयबलीयस्त्वादन्यत्रापि । ३४५५ प्रयोजनं रमाक्षेपि-यङ्वणः । ३४५६ व्यचेः कुटादित्वमनस्यञ्चिति संप्रसारणार्थम् ॥

१ । २० न वशः २६४६ ॥ ३४५७ वशेर्यङि प्रतिषेधः ॥

१ । २७ शृतं पाके ३०६७ ॥ ३४५८ श्राश्रप्योः शृभावः । ३४५९ क्षीरहविषोरिति वाच्यम् । ३४६० श्रपेः शृतमन्यत्र हेतोः ॥

१ । २८ प्यायः पी ३०७२ ॥ ३४६१ आङ्पूर्वादन्धूधसोः ॥

१ । ३० विभाषा श्वेः २४२० ॥ ३४६२ श्वेर्लिट्यभ्यासलक्षणप्रतिषेधः ॥

१ । ३२ ह्वः संप्रसारणम् २५८६ ॥ ३४६३ ह्वः संप्रसारणे योगविभागः । ३४६४ णौ च संश्चङ्क्यार्थः । ३४६५ अभ्यस्तनिमित्तेऽनभ्यस्तप्रसारणार्थम् । ३४६६ अभ्यस्तप्रसारणे ह्यभ्यास-संप्रसारणाप्राप्तिः । ३४६७ समानाङ्गे प्रसारणप्रतिषेधात्प्रतिषेधः । ३४६८ कृदन्तप्रतिषेधार्थं च ॥

१ । ३७ न संप्रसारणे संप्रसारणम् ३६३ ॥ ३४६९ समानाङ्गग्रहणं च । ३४७० तत्रोपोगुपि दोषः । ३४७१ न वा यस्याङ्गस्य प्रसारणप्राप्तिस्तस्मिन्प्राप्तिप्रतिषेधात् । ३४७२ ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि । ३४७३ रयेर्मतौ बहुलम् । ३४७४ कक्ष्यायाः संज्ञायाम् ॥

१ । ४५ आदेच उपदेशेऽशिति २३७० ॥ ३४७५ आत्व एत्युपसंख्यानम् । ३४७६ अशित्येकादेशे प्रतिषेध आदिवत्त्वात् । ३४७७ प्रत्ययविधिः । ३४७८ अभ्यासरूपं च । ३४७९ अवयवानां प्रतिषेधश्च । ३४८० शिति प्रतिषेधे श्लुलुकोरुपसंख्यानं ररौ ध्वं नाध्वं शिशीते । ३४८१ प्रातिपदिकप्रतिषेधः । ३४८२ धात्वधिकारात्प्रातिपदिकस्याप्राप्तिः ॥

१ । ४८ क्रीङ्जीनां णौ २६०० ॥ ३४८३ आत्त्वे णौ लीयतेरुपसंख्यानं प्रलम्भनशा-लीनीकरणयोः ॥

१ । ४९ सिध्यतेरपारलौकिके २६०२ ॥ ३४८४ सिध्यतेरज्ञानार्थस्य । ३४८५ इतरथा ह्यनिष्टप्रसङ्गः ॥

१ । ५० मीनातिमिनोतिदीङां ल्यपि च २५०८ ॥ ३४८६ मीनात्यादीनामात्त्व उपदे-शवचनं प्रत्ययविध्यर्थम् । ३४८७ निमिमीलियां खलचोः प्रतिषेधः ॥

१ । ५८ सृजिदृशोर्झल्यमकिति २४०५ ॥ ३४८८ अमि सङ्ग्रहणम् । ३४८९ क्विप्प्रतिषेधार्थम् ॥

१ । ६० शीर्षंश्छन्दसि ३५१४ ॥ ३४९० शीर्षंश्छन्दसि प्रकृत्यन्तरम् । ३४९१ आदे-शप्रतिषेधार्थम् ॥

१ । ६१ ये च तद्धिते १६६७ ॥ ३४९२ ये च तद्धिते शिरस आदेशवचनम् । ३४९३ वा केशेषु । ३४९४ अग्रिं शीर्षः । ३४९५ छन्दसि च ॥

१ । ६३ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु २२८॥ ३४९६ पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् । ३४९७ नस्नासिकाया यत्तस्क्षुद्रेषु । ३४९८ अवर्णनगरयोरिति वक्तव्यम् ॥

१ । ६४ धात्वादेः षः सः २२६४ ॥ ३४९९ सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधः॥

१ । ६६ लोपो व्योर्वलि ८७३ ॥ ३५०० व्योर्लोपे क्वावुपसंख्यानम् । ३५०१ वलोपात्सिद्धिरूठ्भावप्रसङ्गात् । ३५०२ अतिप्रसङ्गो व्रश्चादिषु । ३५०३ उपदेशसामर्थ्यात्सिद्धम् । ३५०४ उपदेशसामर्थ्यात्सिद्धमिति चेत्संप्रसारणहलादिशेषेषु सामर्थ्यम् । ३५०५ न वा बहिरङ्गलक्षणत्वात् । ३५०६ अनारम्भो वा । ३५०७ आस्रेमाणं जीरदानुरिति वर्णलोपात् । ३५०८ यथा संस्फानो गयस्फानः ॥

१ । ६७ वेरपृक्तस्य ३७५ ॥ ३५०९ दर्विजागृभ्योः प्रतिषेधो वक्तव्यः । ३५१० वेर्लोपे दर्विजागृभ्योरप्रतिषेधोऽनुनासिकपरत्वात् । ३५११ धात्वन्तस्य चार्थवत्त्वात् । ३५१२ वस्य वानुनासिकत्वात्सिद्धम् ॥

१ । ६८ हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् २५२ ॥ ३५१३ हलन्तादपृक्तलोपसंयोगान्तलोपश्चेन्नलोपाभावो यथा पचन्निति । ३५१४ वस्वादिषु दत्वं संयोगादिलोपबलीयस्त्वात् । ३५१५ यथा कूटतडिति । ३५१६ रात्सलोपो नियमवचनात् । ३५१७ रोरुत्वं च । ३५१८ न वा संयोगान्तलोपस्योत्त्वे सिद्धत्वात् । ३५१९ यथा हरिवो मेदिनमिति ॥

१ । ६९ एङ्ह्रस्वात्संबुद्धेः १९३ ॥ ३५२० संबुद्धिलोपे डतरादिभ्यः प्रतिषेधः । ३५२१ अपृक्ताधिकारस्य निवृत्तत्वात् । ३५२२ तच्चामर्थम् । ३५२३ अपृक्तसंबुद्धिलोपाभ्यां लुक् । ३५२४ न वा लोपलुकोर्लिङ्गवधारणाद्यथानड्वुत इति ॥

१ । ७१ ह्रस्वस्य पिति कृति तुक् २८९८ ॥ ३५२५ तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वं द्विगुस्वरश्च । ३५२६ न वा बहिरङ्गलक्षणत्वात् ३५२७ ग्रामणिपुत्रादिषु चाप्राप्तिः । ३५२८ परादौ संयोगादेरित्यतिप्रसङ्गः । ३५२९ विलोपवचनं च । ३५३० इट्प्रतिषेधश्च । ३५३१ अभक्ते स्वरः ॥

१ । ७४ आङ्माङोश्च १४७ ॥ ३५३२ आङ्माङोः सानुबन्धकनिर्देशो गतिकर्मप्रवचनीयप्रतिषेधसंप्रत्ययार्थः ॥

१ । ७५-७६ दीर्घात् १४८ । पदान्ताद्वा १४९ ॥ ३५३३ दीर्घात्पदान्ताद्वा विश्वजनादीनां छन्दसि ॥

१ । ७७ इको यणचि ४७ ॥ ३५३४ जश्त्वं न सिद्धं यणमत्र पश्य । ३५३५ यश्चपदान्तो हलचश्च पूर्वः । ३५३६ दीर्घस्य यण् । ३५३७ ह्रस्व इति प्रवृत्तम् । ३५३८ संबन्धवृत्त्या । ३५३९ गुणवृद्धिबाध्यः ॥ ३५४० यणादेशः प्लुतपूर्वस्य च । ३५४१ दीर्घशाकलप्रतिषेधार्थम् ।

१ । ७९ वान्तो यि प्रत्यये ६३ ॥ ३५४२ वान्तादेशे स्थानिनिर्देशः । ओकारौकारयोरिति । ३५४३ गोर्यूतौ छन्दसि । ३५४४ अध्वपरिमाणे च ॥

१ । ८३ भय्यप्रवय्ये च च्छन्दसि ३५१७ ॥ ३५४५ भय्यादिप्रकरणे ह्रदय्या उपसं-

ख्यानम् । ३५४६ अब् शरस्य च । ३५४७ शरुवृत्ताद्वा सिद्धम् । ३५४८ ऋज्जती शरारि-त्यपि दृश्यते । ३५४९ शरुहस्त इति च लोके ॥

१ । ८४ एकः पूर्वपरयोः ६८ ॥ ३५५० एकवचनं पृथगादेशप्रतिषेधार्थम् । ३५५१ न वा द्रव्यवत्कर्मचोदनायां द्वयोरेकस्याभिनिर्वृत्तिः । ३५५२ तथैकवाक्यभावात् । ३५५३ तत्रावयवे शास्त्रार्थसंप्रत्ययो यथा लोके । ३५५४ सिद्धं तु धर्मोपदेशनेऽनवयवविज्ञानाद्यथा लौकिक-वैदिकेषु । ३५५५ पूर्वपरग्रहणं परस्यादेशप्रतिषेधार्थम् । ३५५६ पञ्चमीनिर्दिष्टाद्धि परस्य । ३५५७ षष्ठीनिर्दिष्टार्थं तु । ३५५८ अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः ॥

१ । ८५ अन्तादिवच्च ७५ ॥ ३५५९ अन्तादिवद्वचनमामिश्रस्यादेशवचनात् । ३५६० तत्र यस्यान्तादिवत्तन्निर्देशः । ३५६१ सिद्धं तु पूर्वपराधिकारात् । ३५६२ अन्तवत्त्वे प्रयोजनं बह्वच्पूर्वपदाट्ठज्विधाने । ३५६३ प्रत्ययैकादेशः पूर्वविधौ । ३५६४ वैभक्तस्य णत्वे । ३५६५ अदस ईत्वोत्वे । ३५६६ स्वस्तित्वं विप्रतिषेधात् । ३५६७ लिङ्गविशिष्टग्रहणाद्वा । ३५६८ पूर्वपदान्तोदात्तत्वं च । ३५६९ एकादेशे हि स्वरिताप्रसिद्धिः । ३५७० कृदन्तप्रकृतिस्वरत्वं च । ३५७१ एकादेशे ह्यप्रसिद्धिरुत्तरपदस्यापरत्वात् । ३५७२ उत्तरपदवृद्धिश्चैकादेशात् । ३५७३ एकादेशप्रसङ्गस्त्वन्तरङ्गबलीयस्त्वात् । ३५७४ तत्र वृद्धिविधानम् । ३५७५ आदिवत्त्वे प्रयोजनं प्रगृह्यसंज्ञायाम् । ३५७६ सुप्तिङन्तविधिषु । ३५७७ आङ्ग्रहणे पदविधौ । ३५७८ आटश्च वृद्धिविधौ । ३५७९ कृदन्तप्रातिपदिकत्वे च । ३५८० नाभ्यासादीनां ह्रस्वत्वे । ३५८१ न वा बहिरङ्गलक्षणत्वात् । ३५८२ वर्णौ अयविधौ च । ३५८३ प्रयोजनं खट्वाभिर्जुहा-वास्या अश्व इति । ३५८४ न वानाद्भ्यातिदेशात् ॥

१ । ८६ षत्वतुकोरसिद्धः ३३३३ ॥ ३५८५ षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषे-धार्थमुत्सर्गलक्षणभावार्थं च । ३५८६ तत्रोत्सर्गलक्षणाप्रसिद्धिरुत्सर्गाभावात् । ३५८७ असिद्धवचनात्सिद्धमिति चेन्नान्यस्यासिद्धवचनादन्यस्य भावः । ३५८८ तस्मात्स्थानिवद्वच-नमसिद्धत्वं च । ३५८९ स्थानिवद्वचनानर्थक्यं शास्त्रासिद्धत्वात् । ३५९० संप्रसारणङीट्सु सिद्धः । ३५९१ संप्रसारणङीट्सु सिद्धः पदान्तपदाद्योरेकादेशस्यासिद्धवचनम् ॥

१ । ८७ आद्गुणः ६९ ॥ ३५९२ आदेकश्चेद्गुणः केन । ३५९३ स्थानेऽन्तरतमो हि सः । ३५९४ ऐदौतौ नेचि तावुक्तौ । ३५९५ ऋकारो नोभयान्तरः ॥ ३५९६ आकारो नार्तिं धातौ सः । ३५९७ प्लुतश्च विषये स्मृतः । ३५९८ आन्तर्याच्चित्रचतुर्मात्राः । ३५९९ तपरत्वान्न ते स्मृताः । ३६०० गुणे ङिशीटामुपसंख्यानं दीर्घत्वबाधनार्थम् । ३६०१ न वा बहिरङ्गलक्ष-णत्वात् ॥

१ । ८९ एत्येधत्यूठ्सु ७३ ॥ ३६०२ इणीकारादौ प्रतिषेधः । ३६०३ योगविभागात्सि-द्धम् । ३६०४ अक्षादूहिन्याम् । ३६०५ प्रादूहोढोढ्येषैष्येषु । ३६०६ स्वादीरेरिणोः । ३६०७ ऋते च तृतीयासमासे । ३६०८ प्रवत्सतरकम्बलवसनां चर्णे । ३६०९ ऋणद-शाभ्यां च ॥

१ । ९१ उपसर्गादृतिधातौ ७४ ॥ ३६१० छे तुकः संबुद्धिगुणः । ३६११ न वा बहि-रङ्गलक्षणत्वात् । ३६१२ संप्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च । ३६१३ यणादेशादागुणः । ३६१४ इरुर्गुणवृद्धिविधयश्च । ३६१५ भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्ति-

स्वरा एकादेशाच । ३६१६ अङ्गोपाङ्गौ चार्धधातुके । ३६१७ इयङ्उवङ्गुणवृद्धिदित्विन्मित्पूर्वपदविकाराश्च । ३६१८ उत्तरपदविकाराश्चेति वक्तव्यम् ॥

१ । ९३ औतोऽम्शसोः २८९ ॥ ३६१९ ओतस्तिङि प्रतिषेधः । ३६२० गोग्रहणे योरुपसंख्यानम् । ३६२१ समासाच्च प्रतिषेधः । ३६२२ न वा बहिरङ्गलक्षणत्वात् । ३६२३ सवधिकारात्सिद्धम् । ३६२४ एकयोगे चैकदेशानुवृत्तिरन्यथापि । ३६२५ अम्युपसंख्यानं वृद्धिबलीयस्त्वात् । ३६२६ न वानवकाशत्वात् । ३६२७ योश्च सर्वनामस्थाने वृद्धिविधिः । ३६२८ यद्यचाव इन्द्रेति दर्शनात् ॥

१ । ९४ एङि पररूपम् ७८ ॥ ३६२९ पररूपप्रकरणे तुन्त्रोर्विनिपात उपसंख्यानम् । ३६३० न वा निपातैकत्वात् । ३६३१ एवे चानियोगे । ३६३२ शकन्ध्वादिषु च । ३६३३ सीमन्तः केशेष्विति वक्तव्यम् । ३६३४ ओत्वोष्ठयोः समासे वा । ३६३५ एमन्नादिषु छन्दसि ॥

१ । ९५ ओमाङोश्च ८० ॥ ३६३६ उस्योमाङ्क्ष्वाटः प्रतिषेधः ॥

१ । ९८ अव्यक्तानुकरणस्यात इतौ ८१ ॥ ३६३७ इतावनेकाज्ग्रहणं श्रदर्थम् ॥

१ । ९९ नाम्रेडितस्यान्त्यस्य तु वा ८२ ॥ ३६३८ नित्यमाम्रेडिते डाचि । ३६३९ अकारान्तानुकरणाद्वा ॥

१ । १०१ अकः सवर्णे दीर्घः ८५ ॥ ३६४० सवर्णदीर्घत्व ऋति ऋ वावचनम् । ३६४१ लृति लृवावचनम् ॥

१ । १०२ प्रथमयोः पूर्वसवर्णः १६४ ॥ ३६४२ प्रथमयोरिति योगविभागः सवर्णदीर्घार्थः । ३६४३ एकयोगे हि जश्शसोः पररूपप्रसङ्गः । ३६४४ आद्गुणयणादेशयोरपवादा वृद्धिसवर्णदीर्घपूर्वसवर्णादेशास्तेषां पररूपं स्वरसंधिषु । ३६४५ योगविभागोऽन्यशास्त्रनिवृत्त्यर्थः । ३६४६ योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यातिप्रसङ्गः । ३६४७ नकाराभावश्च तस्मादित्यनन्तरनिर्देशात् । ३६४८ इज्ग्रहणं तु ज्ञापकं पररूपाभावस्य ॥

१ । १०३ तस्माच्छसो नः पुंसि १९६ ॥ ३६४९ नत्वं पुंसां बहुत्वे चेत्पुंशब्दादिष्यते स्त्रियाम् । ३६५० नपुंसके तथैवेष्टम् । ३६५१ स्त्रीशब्दाच्च प्रसज्यते ॥ ३६५२ पुंशब्दादिति चेदिष्टं स्थूरापत्ये न सिध्यति । कुण्डिन्या अररकायाः । ३६५३ पुंस्प्राधान्यात्प्रसिध्यति ॥ ३६५४ पुंस्प्राधान्ये त एव स्युर्ये दोषाः पूर्वचोदिताः । ३६५५ तस्मादर्थे भवेन्नत्वं वध्रिकादिषु पूर्ववत् ॥

१ । १०७ अमि पूर्वः १९४ ॥ ३६५६ वा छन्दसीत्येव ॥

१ । १०८ संप्रसारणाच्च ३३० ॥ ३६५७ वा छन्दसीत्येव । ३६५८ संप्रसारणात्पूर्वत्वे समानाङ्गग्रहणं समानाङ्गप्रतिषेधार्थम् । ३६५९ सिद्धमसंप्रसारणात् । ३६६० कार्यकृतत्वाद्वा । ३६६१ दीर्घत्वं वचनप्रामाण्यात् । ३६६२ अन्तवत्त्वाद्वा । ३६६३ आटो वृद्धेरियङ् । ३६६४ आद्गुणात्सवर्णदीर्घत्वमाङभ्यासयोः । ३६६५ स्वरदोषस्तु । ३६६६ आङि पररूपवचनं तु ज्ञापकमन्तरङ्गबलीयस्त्वस्य । ३६६७ प्रयोजनं पूर्वसवर्णपूर्वत्वतहिलोपटेनङ्यांङिस्मिन्ङिणलैत्वमन्तरङ्गं बहिरङ्गलक्षणाद्वर्णविकारात् ॥

१ । ११३ अतो रोरप्लुतादप्लुते १६३ ॥ ३६६८ अप्लुतादप्लुतवचनेऽकारहशोः समानपदे प्रतिषेधः । ३६६९ न वा बहिरङ्गलक्षणत्वात् ॥

१ । ११९ नान्तःपादमव्यपरे ३५१८ ॥ ३६७० नान्तःपादमिति सर्वप्रतिषेधश्चेदतिप्रसङ्गः । ३६७१ अकाराश्रयमिति चेदुक्तवचनम् । ३६७२ अयवोः प्रतिषेधश्च । ३६७३ एङ्प्रकरणात्सिद्धमिति चेदुक्तप्रतिषेधः । ३६७४ पुनरेङ्ग्रहणात्सिद्धम् ॥

१ । १२३ अवङ् स्फोटायनस्य ८८ ॥ ३६७५ गोरग्वचनं गवाग्रे स्वरसिद्ध्यर्थम् । ३६७६ अवङादेशे हि स्वरदोषः ॥

१ । १२४ इन्द्रे च नित्यम् ८९ ॥ ३६७७ इन्द्रादाविति वक्तव्यम् ॥

१ । १२५ प्लुतप्रगृह्या अचि ९० ॥ ३६७८ प्लुतप्रगृह्येष्वज्ग्रहणमनर्थकमधिकारात्सिद्धम् । ३६७९ तत्तु तस्मिन्प्रकृतिभावार्थम् । ३६८० प्लुतप्रकृतिभाववचनं तु ज्ञापकमेकादेशात्प्लुतो विप्रतिषेधेनेति । ३६८१ एकादेशात्प्लुतो विप्रतिषेधेनेति चेच्छाल्लेन्द्रेऽतिप्रसङ्गः । ३६८२ न वा बहिरङ्गलक्षणत्वात् ॥

१ । १२६ आङोऽनुनासिकश्छन्दसि ३५२९ ॥ ३६८३ आङोऽनर्थकस्य ॥

१ । १२७ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ९१ ॥ ३६८४ सित् (नित्य) समासयोः शाकलप्रतिषेधः । ३६८५ ईषाअक्षादिषु च्छन्दसि प्रकृतिभाववचनम् ॥

१ । १२८ ऋत्यकः ९२ ॥ ३६८६ ऋत्यकः सवर्णार्थम् । ३६८७ अनिगन्तार्थं च । ३६८८ ऋति ह्रस्वादुपसर्गाद्वृद्धिर्विप्रतिषेधेन ॥

१ । १२९ अप्लुतवदुपस्थिते ९८ ॥ ३६८९ वद्वचनं प्लुतकार्यप्रतिषेधार्थम् । ३६९० प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात् ॥

१ । १३० ई३ चाक्रवर्मणस्य ९९ ॥ ३६९१ ई३ चाक्रवर्मणस्येत्यनुपस्थितार्थम् ॥

१ । १३५ सुट् कात्पूर्वः २५५३ ॥ ३६९२ सुटि कात्पूर्ववचनमककारादौ कात्पूर्वार्थम् । ३६९३ सुटि कात्पूर्ववचनमककारादौ कात्पूर्वार्थमिति चेदन्तरेणापि तत्सिद्धम् । ३६९४ द्विर्वचनात्सुड्विप्रतिषेधेन । ३६९५ द्विर्वचनात्सुड्विप्रतिषेधेनेति चेद्द्विर्भूते शब्दान्तरभावात्पुनःप्रसङ्गः । ३६९६ द्विर्भूते शब्दान्तरभावात्पुनः प्रसङ्ग इति चेद्द्विर्वचनम् । ३६९७ तथा चानवस्था । ३६९८ अड्व्यवाय उपसंख्यानम् । ३६९९ अभ्यासव्यवाये च । ३७०० अविप्रतिषेधो वा बहिरङ्गलक्षणत्वात् । ३७०१ उपदेशिवद्वचनं च । ३७०२ लिटि गुणवृद्धि दीर्घप्रतिषेधार्थम् । ३७०३ कात्पूर्वान्त इति चेद्गुविधिप्रतिषेधः । ३७०४ परादाविड्गुणप्रसङ्गः । ३७०५ अभक्ते स्वरः ॥

१ । १४२ अपाच्चतुष्पाच्छकुनिष्वालेखने २६८८ ॥ ३७०६ किरतेर्हर्षजीविकाकुलायकरणेषु ॥

१ । १४४ अपरस्पराः क्रियासातत्ये १०५९ ॥ ३७०७ समो हिततततयोर्वा लोपः । ३७०८ सन्तुमुनोः कामे । ३७०९ मनसि च । ३७१० अवश्यमः कृत्ये ॥

१ । १५० विष्किरः शकुनौ वा १०६५ ॥ ३७११ विष्किरः शकुनौ विकिरो वा ।

१ । १४७ आश्चर्यमनित्ये १०६२ ॥ ३७१२ आश्चर्यमद्भुते ॥

१ । १५७ पारस्करप्रभृतीनि च संज्ञायाम् १०७१ ॥ ३७१३ तद्बृहतोः करपत्योश्चौरदेवतयोः सुट्तलोपश्च । ३७१४ प्रायस्य चित्तिचित्तयोः सुडस्कारो वा ॥

१ । १५८ अनुदात्तं पदमेकवर्जम् ३६५० ॥ ३७१५ आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च । ३७१६ पृथक्स्वरनिवृत्त्यर्थमेकवर्जं पदस्वरः ॥ ३७१७ यौगपद्यं तवै सिद्धम् । ३७१८ पर्यायो रिक्तशासनात् । ३७१९ उदात्ते ज्ञापकं त्वेतत् । ३७२० स्वरितेन समावेशेत् । ३७२१ अनुदात्ते विप्रतिषेधानपपानिरेकस्मिन्युगपत्संभवात् । ३७२२ सिद्धं त्वेकानुदात्तत्वात् । ३७२३ एकवर्जमिति चाप्रसिद्धिः संदेहात् । ३७२४ सिद्धं तु यस्मिन्ननुदात्त उदात्तवचनानर्थक्यं तद्वर्जम् । ३७२५ प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वादप्रसिद्धिः । ३७२६ विप्रतिषेधात्प्रत्ययस्वरः । ३७२७ विप्रतिषेधात्प्रत्ययस्वर इति चेत्काम्यायादिषु चित्करणम् । ३७२८ प्रकृतिस्वरे प्रत्ययस्वराभावः । ३७२९ सिद्धं तु प्रकृतिस्वरबलीयस्त्वात्प्रत्ययस्वराभावः । ३७३० सति शिष्टस्वरबलीयस्त्वं च । ३७३१ तच्चानेकप्रत्ययसमासार्थम् । ३७३२ स्यादिस्वराप्रसङ्गश्च तासेः परस्यानुदात्तवचनात् । ३७३३ शास्त्रपरविप्रतिषेधानियमाद्वा शब्दपरविप्रतिषेधाद्वा सिद्धम् । ३७३४ विभक्तिस्वरान्नञ्स्वरो बलीयान् ॥ ३७३५ विभक्तिनिमित्तस्वराच्च । ३७३६ यच्चोपपदं कृति नञ् । ३७३७ सहनिर्दिष्टस्य च ॥

१ । १६१ अनुदात्तस्य च यत्रोदात्तलोपः ३६९१ ॥ ३७३८ उदात्तलोपे स्वरितोदात्तयोरभावादनुदात्तग्रहणानर्थक्यम् । ३७३९ अन्त इति चेच्छ्भ्मक्स्युष्मदस्मदिदंकिंलोपेषु स्वरः ॥ ३७४० आदिरिति चेदिन्धीत द्वय मित्यन्तः । ३७४१ आदौ सिद्धम् । ३७४२ विदीन्धिखिदिभ्यश्च लसार्वधातुकानुदात्तप्रतिषेधाच्छिङि सिद्धम् । ३७४३ अयाचि चित्करणात् ॥

१ । १६२ धातोः ३६७१ ॥ ३७४४ धातोरन्त इति चेदनुदात्तेचश्च ग्रहणम् । ३७४५ संश्च नित् । ३७४६ आदावूर्णुप्रत्ययधातुष्वन्तोदात्तत्वम् । ३७४७ अन्तोदात्तवचनात्सिद्धम् ३७४८ पिबौ निपातनात् ॥

१ । १६३ चितः ३७१० ॥ ३७४९ चितः सप्रकृतेर्बह्वकजर्थम् ॥

१ । १६६ तिसृभ्यो जसः ३७१३ ॥ ३७५० तिसृभ्यो जस्ग्रहणानर्थक्यमन्यत्राभावात् ।

१ । १६७ चतुरः शसि ३६८२ ॥ ३७५१ चतुरः शसि स्त्रियामप्रतिषेध आद्युदात्तनिपातनात् । ३७५२ विभक्तिस्वरभावश्च हलादिग्रहणात् । ३७५३ आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् ॥

१ । १६८ सावेकाचस्तृतीयादिर्विभक्तिः ३७१४ ॥ ३७५४ सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधः । ३७५५ सिद्धं तु यस्मात्तृतीयादिस्तस्याभावात्सौ । ३७५६ प्रकृतेश्चानकाच्त्वात् ॥

१।१७१ ऊडिदंपदाद्यप्पुम्रैद्युभ्यः ३७१७ ॥ ३७५७ ऊठ्युपधाग्रहणमन्त्यप्रतिषेधार्थम् ॥

१ । १७२ अष्टनो दीर्घात् ३७१८ ॥ ३७५८ अष्टनो दीर्घग्रहणं षट्संज्ञाज्ञापकमाकारान्तस्य नुडर्थम् ॥

१ । १७३ शतुरनुमो नद्यजादी ३७१९ ॥ ३७५९ नद्यजाद्युदात्तत्वे बृहन्महतोरुपसंख्यानम् ॥

१ । १७४ उदात्तयणोर्हल्पूर्वात् ३७२० ॥ ३७६० उदात्तयणि हल्ग्रहणं नकारान्तार्थम् । ३७६१ हल्पूर्वग्रहणानर्थक्यं चसमुदायादेशत्वात् । ३७६२ स्वरितत्वे चावचनात् ॥

१ । १७६ ह्रस्वनुड्भ्यां मतुप् ३७२२ ॥ ३७६३ मतुबुदात्तत्वे रेग्रहणम् । ३७६४ विप्रतिषेधश्च ॥

१ । १७७ नामन्यतरस्याम् ३७२३ ॥ ३७६५ नाम्स्वरे मतौ ह्रस्वग्रहणम् ॥

१ । १८५ तित्स्वरितम् ३७२९ ॥ ३७६६ तिति प्रत्ययग्रहणम् ॥

१ । १८६ तास्यनुदात्तेन्ङिद्दुपदेशाल्लसार्वधातुकमनुदात्तमन्ह्विङोः ३७३० ॥ ३७६७ तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थः । ३७६८ चित्स्वरात्तास्यादिभ्योऽनुदात्तत्वं विप्रतिषेधेन । ३७६९ मुकश्चोपसंख्यानम् । ३७७० इतश्चोपसंख्यानम् । ३७७१ इतश्चानेकान्तत्वात् । ३७७२ तत्रादिप्रभृतिजुहोत्यादिभ्योऽप्रतिषेधः स्थान्यादेशभावात् । ३७७३ अनुदात्तङिद्ग्रहणाद्वा । ३७७४ ङितोऽनुदात्तत्वे विकरणेभ्यः प्रतिषेधः । ३७७५ ङितोऽनुदात्तत्वे विकरणेभ्योऽप्रतिषेधः सर्वस्योपदेशविशेषणत्वात् ॥

१ । १८७ आदिः सिचोऽन्यतरस्याम् ३७३१ ॥ ३७७६ सिच आद्युदात्तत्वेऽनिटः पित उपसंख्यानम् ॥

१ । ८८ स्वपादिर्हिंसामच्यनिटि ३६७२ ॥ ३७७७ स्वपादीनां वावचनादभ्यस्तस्वरो विप्रतिषेधेन ॥

१ । १९० अनुदात्ते च ६७४ ॥ ३७७८ अनुदात्ते चेति बहुव्रीहिनिर्देशो लोपयणादेशार्थः ॥

१ । १९१ सर्वस्य सुपि३६८९ ॥ ३७७९ सर्वस्वरोऽनचकस्य ॥

१ । १९५ अचः कर्तृयकि ३६७८ ॥ ३७८० यकि रपर उपसंख्यानम् । ३७८१ उपदेशवचनात्सिद्धम् । ३७८२ उपदेशवचने जनादीनाम् । ३७८३ योगविभागात्सिद्धम् ॥

१ । २०४ संज्ञायामुपमानम् ३६९५ ॥ ३७८४ उपमानस्याद्युदात्तवचनं ज्ञापकमनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य ॥

१ । २०५ निष्ठा च द्व्यजनात् ३६९३ ॥ ३७८५ निष्ठायां यजि दीर्घत्वे प्रतिषेधः । ३७८६ न वा बहिरङ्गलक्षणत्वात् ॥

१ । २०७ आशितः कर्ता ३६९९ ॥ ३७८७ आशिते कर्तरि निपातनमुपधादीर्घत्वमाद्युदात्तत्वं च ॥

१ । २०८-२१५ रिक्ते विभाषा ३६९६ । विभाषा वेण्विन्धानयोः ३७०३ ॥ ३७८८ वेणुरिक्तयोरप्राप्ते ॥

१ । २२२ चौ ३६५२ ॥ ३७८९ चोरतद्धिते ॥

१ । २२३ समासस्य ३७३४ ॥ ३७९० समासान्तोदात्तत्वे व्यञ्जनान्तेषूपसंख्यानम् । ३७९१ हल्स्वरप्राप्तौ वा व्यञ्जनमविद्यमानवत् । ३७९२ प्रयोजनं लिदाद्युदात्तान्तोदात्तविधयः ॥

२ । १ बहुव्रीहौ पूर्वपदं प्रकृत्या ३७३५ ॥ ३७९३ बहुव्रीहिस्वरं शास्ति समासान्तविधेः सुकृत् । ३७९४ नञ्सुभ्यां नियमार्थं तु । ३७९५ परस्य शिति शासनात् ॥ ३७९६ क्षेपे विधिर्नञोऽसिद्धः । ३७९७ परस्य नियमो भवेत् । ३७९८ अन्तश्च वाप्रिये सिद्धः । ३७९९

संभवात् । ३८०० प्रकृताद्विधेः ॥ ३८०१ बहुव्रीहावृते सिद्धम् । ३८०२ इष्टतश्चावधारणात् । ३८०३ द्विपादिष्टेर्वितस्तेश्च पर्यायो न प्रकल्पते ॥ ३८०४ उदात्ते ज्ञापकं त्वेतत् । ३८०५ स्वरितेन समाविशेत् ॥

२ । २ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः ३७३६ ॥ ३८०६ तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः । ३८०७ सिद्धं तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् । ३८०८ अव्यये नञ्कुनिपातानाम् । ३८०९ क्त्वायां वा प्रतिषेधः । ३८१० निपातनात्सिद्धम् ॥

२ । ११ सदृशप्रतिरूपयोः सादृश्ये ३७४९ ॥ ३८११ सदृशमनर्थकं तृतीयासमासवचनात् । ३८१२ षष्ठ्यर्थमिति चेत्तृतीयासमासवचनमनर्थक्यम् ॥

२ । २९ इगन्तकालकपालभगालशरावेषु द्विगौ ३७६३ ॥ ३८१३ इगन्तप्रकृतिस्वरत्वे यग्गुणयोरुपसंख्यानम् । ३८१४ न वा बहिरङ्गलक्षणत्वात् ॥

२ । ३३ परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ३७६७ ॥ ३८१५ परिप्रत्युपापेभ्यो वनं समासे विप्रतिषेधेन । ३८१६ न वा वनस्यान्तोदात्तवचनं तदपवादनिवृत्त्यर्थम् ॥

२ । ३६ आचार्योपसर्जनश्चान्तेवासी ३७७० ॥ ३८१७ आचार्योपसर्जनेऽनेकस्यापि पूर्ववदत्वात्संदेहः । ३८१८ लोकविज्ञानात्सिद्धम् ॥

२ । ४२ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ३७३६ ॥ ३८१९ कुरुवृज्योर्गार्हपते । ३८२० पण्यकम्बलः संज्ञायाम् ॥

२ । ४७ अहीने द्वितीया ३७८१ ॥ ३८२१ अहीने द्वितीयानुपसर्गे ॥

२ । ४९ गतिरनन्तरः ३७८३ ॥ ३८२२ गतेरनन्तरग्रहणमनर्थकं गतिर्गतावनुदात्तवचनात् । ३८२३ तत्र यस्य प्रकृतिस्वरत्वं तस्मादन्तोदात्तप्रसङ्गः । ३८२४ प्रकृतिस्वरवचनाद्व्यनन्तोदात्तत्वम् । ३८२५ प्रकृतिस्वरवचनं किमर्थमिति चेदेकगत्यर्थम् । ३८२६ अपूर्वपदार्थमिति चेत्कारकेऽतिप्रसङ्गः । ३८२७ सिद्धं तु गतेरन्तोदात्ताप्रसङ्गात् ॥

२ । ५० तादौ च निति कृत्यतौ ३७८४ ॥ ३८२८ तादौ निति कृद्ग्रहणानर्थक्यम् । ३८२९ कृदुपदेशे वा ताद्यर्थमिडर्थम् ॥

२ । ५२ अनिगन्तोऽञ्चतौ वप्रत्यये ३७८६ ॥ ३८३० अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः । ३८३१ अनिगन्तवचनं किमर्थमिति चेद्यणादिष्टार्थम् । ३८३२ चोरनिगन्तोऽञ्चतौ वप्रत्यये । ३८३३ न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधादितरथा हि सर्वापवादः । ३८३४ विभक्तीषत्स्वरात्कृत्स्वरः । ३८३५ चित्स्वराद्धारिस्वरः । ३८३६ कृत्स्वरश्च । ३८३७ न वा हरणप्रतिषेधो ज्ञापकः कृत्स्वराबाधकत्वस्य । ३८३८ युक्तस्वरश्च ।

२ । ८२ दीर्घकाशतुषभ्राष्ट्रवटं जे ३८१६ ॥ ३८३९ जे दीर्घाद्द्वचः ।

२ । ९१ न भूताधिकसंजीवमद्राश्मकज्जलम् ३८२५ ॥ ३८४० आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ॥

२ । ९३ सर्वं गुणकार्त्स्न्ये ३८५७ ॥ ३८४१ गुणात्तरेण समासस्तरलोपश्च ॥

२ । १०६ बहुव्रीहौ विश्वं संज्ञायाम् ३८४० ॥ ३८४२ बहुव्रीहौ विश्वस्यान्तोदात्तात्सं-ज्ञायां मित्राजिनयोरन्तः । ३८४३ अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दस्युपसंख्यानम् ॥

२ । १०७-१०८ उदराश्वेषुषु ३८४१ । क्षेपे ३८४२ ॥ ३८४४ उदरादिभ्यो नञ्सुभ्याम् ॥

२ । ११७ सौमनसी अलोमोषसी ३८५१ ॥ ३८४५ सौमनसोः कपि ॥

२ । १२१ कूलतीरतूलमूलशालाक्षसममव्ययीभावे ३८५५ ॥ ३८४६ पर्यादिभ्यः कूलादीनामाद्युदात्तत्वम् ॥

२ । १२६ चेलखेटकटुककाण्डगर्हायाम् ३८६० । १३० अकर्मधारये राज्यम् ३८६४ ॥ ३८४७ चेलराज्यादिभ्योऽव्ययम् ॥

२ । १३६ कुण्डं वनम् ३८७० ॥ ३८४८ कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् ॥

२ । १३९ गतिकारकोपपदात्कृत् ३८७३ ॥ ३८४९ गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणा-नर्थक्यमन्यस्योत्तरपदस्याभावात् । ३८५० कृत्प्रकृतौ गतित्वादधिकार्थं कृद्ग्रहणम् ॥

२ । १४३ अन्तः ३८७७ ॥ ३८५१ अन्तोदात्तत्वं समासस्येति चेत्कप्युपसंख्यानम् । ३८५२ उत्तरपदस्यान्तोदात्तत्वे नञ्सुभ्यां समासान्तोदात्तत्वम् । ३८५३ न वा कपि पूर्ववचन ज्ञापकमुत्तरपदान्तोदात्तत्वस्य । ३८५४ प्रकरणाच्च समासान्तत्वम् ॥

२ । १४८ कारकाद्दत्तश्रुतयोरेवाशिषि ३८८२ ॥ ३८५५ कारकाद्दत्तश्रुतयोरनाशिषि प्रतिषेधः । ३८५६ सिद्धं तूभयनियमात् ॥

२ । १६९ संज्ञायां मित्राजिनयोः ३८९९ ॥ ३८५७ ऋषिप्रतिषेधो मित्रे ॥

२ । १७५ बह्वोर्नञ्वदुत्तरपदभूम्नि ३९०९ ॥ ३८५८ बह्वोर्नञ्वदुत्तरपदाद्युदात्तार्थम् ।

२ । १७७ उपसर्गात्स्वाङ्गं ध्रुवमपर्शु ३९११ ॥ ३८५९ उपसर्गात्स्वाङ्गं ध्रुवं मुखस्या-न्तोदात्तत्वात् ॥

२ । १८५-१८६ अभेर्मुखम् ३९१९ । अपाच्च ३९२० ॥ ३८६० अभेर्मुखमपाच्चाध्रु-वार्थम् । ३८६१ अबहुव्रीह्यर्थं वा ॥

२ । १८७ स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम च ३९२१ ॥ ३८६२ स्फिगपू-तग्रहणं च ॥

२ । १९१ अतेरकृत्पदे ३९२५ ॥ ३८६३ अतेर्धातुलोपे ॥

२ । १९७ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ३९३१ ॥ ३८६४ द्वित्रिभ्यां मूर्धन्यकारा-न्तग्रहणं चेन्नकारान्तस्योपसंख्यानम् । ३८६५ नकारान्तेऽकारान्तस्य । ३८६६ उदात्त-लोपात्सिद्धम् ॥

२ । १९९ परादिश्छन्दसि बहुलम् ३९३३ ॥ ३८६७ परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते । ३८६८ पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं स्मृतः ॥ ३८६९ अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानम् ॥

३ । १ अलुगुत्तरपदे ९५८ ॥ ३८७० उत्तरपदाधिकारस्य प्रयोजनं स्तोकादिभ्यो-ऽलुगानङ्कोहृस्वनलोपाः । ३८७१ एकवच्च । ३८७२ एकवद्वचनमनर्थकम् । ३८७३

द्विबहुष्वसमासः । ३८७४ एकवचने हि गोषुचरेऽतिप्रसङ्गः । ३८७५ वर्षाभ्यश्च जे । ३८७६ अपो योनियन्मतिषु चोपसंख्यानम् । ३८७७ जे चरे च ॥

३ । २ पञ्चम्याः स्तोकादिभ्यः ९५९ ॥ ३८७८ पञ्चमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानम् । ३८७९अन्यार्थे च ॥

३ । ३ ओजःसहोम्भस्तमसस्तृतीयायाः ९६० ॥ ३८८० अञ्जस उपसंख्यानम् । ३८८१ पुंसानुजो जनुषान्धो विकृताक्ष इति च ॥

३ । ५ आज्ञायिनि च ९६२ ॥ ३८८२ आत्मनश्च पूरणे । ३८८३ अन्यार्थे च ॥

३ । ७-८ वैयाकरणाख्यायां चतुर्थ्याः ९६४ । परस्य च ९६५ ॥ ३८८४ आत्मनेभाषपरस्मैभाषयोरुपसंख्यानम् ॥

३ । ९ हलदन्तात्सप्तम्याः संज्ञायाम् ९६६ ॥ ३८८५हृद्द्युभ्यां ङेरुपसंख्यानम् । ३८८६ अन्यार्थे च । ३८८७ हलदन्ताधिकारे गोरुपसंख्यानम् । ३८८८ लुकोऽवादेशौ विप्रतिषेधेन । ३८८९ लुकोऽवादेशौ विप्रतिषेधेनेति चेद्भूमिपाशेऽतिप्रसङ्गः । ३८९० अकात इति वा संध्यक्षरार्थम् ॥

३ । १० कारनाम्नि च प्राचां हलादौ ९६८ ॥ ३८९१ कारनाम्नि वावचनं चेदजादावतिप्रसङ्गः । ३८९२ अप्राप्ते समासविधानम् । ३८९३ योगविभागात्सिद्धम् ॥

३ । ११ मध्याद्गुरौ ९६९ ॥ ३८९४ गुरावन्ताच्च ॥

३ । १४ तत्पुरुषे कृति बहुलम् ९७२ ॥ ३८९५ तत्पुरुषे कृति बहुलमकर्मधारये । ३८९६ लुगलुगनुक्रमणं बहुलवचनस्याकृत्स्नत्वात् ॥

३ । २१ षष्ठ्या आक्रोशे ९७९ ॥ ३८९७ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषूपसंख्यानम् । ३८९८ आमुष्यायणामुष्यपुत्रिकेत्युपसंख्यानम् । ३८९९ आमुष्यकुलिकेति च वक्तव्यम् । ३९०० देवानांप्रिय इति च । ३९०१ शेपपुच्छलाङ्गूलेषु शुनः संज्ञायाम् । ३९०२ दिवश्च दासे ॥

३ । २३ ऋतो विद्यायोनिसंबन्धेभ्यः ९८१ ॥ ३९०३ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणम् ॥

३ । २५ आनङृतो द्वन्द्वे ९२१ ॥ ३९०४ ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् । ३९०५ कार्यी चानिर्दिष्टः । ३९०६ अविशेषेण पितृपितामहादिष्वतिप्रसङ्गः ॥

३ । २६ देवताद्वन्द्वे च ९२२ ॥ ३९०७ देवताद्वन्द्व उभयत्र वायोः प्रतिषेधः । ३९०८ ब्रह्मप्रजापत्यादीनां च ॥

३ । २८ इद्वृद्धौ ९२५ ॥ ३९०९ इद्वृद्धौ विष्णोः प्रतिषेधः ॥

३ । ३४ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ८३१ ॥ ३९१० पुंवद्भावे स्त्रीग्रहणं प्रत्ययग्रहणं चेत्तत्र पुंवदित्युत्तरपदे तन्प्रतिषेधविज्ञानम् ।

---

१ भाष्ये दृश्यमानोऽपि 'मतिषु' इति पाठोऽसांप्रदायिको हरदत्तोक्तिविरोधात् इति शब्दरत्नम् । मतिष्विति युक्तः पाठः । 'एकवच' इत्यस्यातिप्रसङ्गव्याजेनाप्सुजाप्सुचरादिवदस्य भाष्ये उपन्यासात् । नह्यप्सुमन्तावित्यत्र तस्य प्रसङ्गोऽस्ति । शब्दपरतया तस्यैकत्वमात्रार्थत्वात् । किंच 'मतुषु' इति पाठे फलं चिन्त्यम् । अस्य वामीयमित्यादाविव लुकोऽप्राप्तेः । इति तु शेखरः ॥

३९११ प्रातिपदिकस्य च प्रत्यापत्तिः। ३९१२ स्थानिवत्प्रसङ्गश्च। ३९१३ वतण्ड्यादिषु पुंवद्वचनम्। ३९१४ स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत्सर्वप्रसङ्गोऽविशेषात्। ३९१५ भाषितपुंस्कानुपपत्तिश्च। ३९१६ अर्थातिदेशे विप्रतिषेधानुपपत्तिः। ३९१७ पूरण्यां प्रधानपूरणीग्रहणम्॥

३। ३५ तसिलादिष्वा कृत्वसुचः ८३६॥ ३९१८ तसिलादौ त्रतसौ। ३९१९ तरप्तमपौ। ३९२० चरड्जातीयरौ। ३९२१ कल्पब्देशीयरौ। ३९२२ रूपप्पाशपौ। ३९२३ थम्थालौ। ३९२४ दार्हिलौ। ३९२५ तिल्थ्यनौ। ३९२६ शसि बह्वल्पार्थस्य। ३९२७ त्वतलोर्गुणवचनस्य। ३९२८ भस्याढे तद्धिते। ३९२९ ठक्छसोश्च॥

३। ३६ क्यङ्मानिनोश्च ८३७॥ ३९३० मानिन्ग्रहणमव्यर्थमसमानाधिकरणार्थं च॥

३। ३७ न कोपधायाः ८३८॥ ३९३१ कोपधप्रतिषेधे तद्धितवुग्रहणम्॥

३। ४० स्वाङ्गाच्चेतोऽमानिनि ८४१॥ ३९३२ स्वाङ्गाच्चेतोऽमानिनि॥

३। ४२ पुंवत्कर्मधारयजातीयदेशीयेषु ७४६॥ ३९३३ पुंवत्कर्मधारये प्रतिषिद्धार्थम्। ३९३४ कुक्कुट्यादीनामण्डादिषु पुंवद्वचनम्। ३९३५ न वास्त्रीपूर्वपदविवक्षितत्वात्। ३९३६ अग्नेरीत्वाद्वरुणस्य वृद्धिर्विप्रतिषेधेन। ३९३७ पुंवद्भावाद्ध्रस्वत्वं खिद्धादिषु॥

३। ४३ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ९८५॥ ३९३८ कृन्नद्याः प्रतिषेधः॥

३। ४६ आन्महतः समानाधिकरणजातीययोः ८०७॥ ३९३९ अन्यप्रकृतिस्त्वमहान्भूतप्रकृतौ महान्भवत्येव। ३९४० तस्मादात्त्वं न स्यात्। ३९४१ पुंवत्तु कथं भवेदत्र। ३९४२ अमहति महान्हि वृत्तस्तद्वाची चात्र भूतशब्दोऽयम्। ३९४३ तस्मात्सिध्यति पुंवत्। ३९४४ निवर्त्यमात्त्वं तु मन्यन्ते। ३९४५ यस्तु महतः प्रतिपदं समास उक्तस्तदाश्रयं ह्यात्त्वम्। ३९४६ कर्तव्यं मन्यन्ते न लक्षणेन लक्षणोक्तश्चायम्॥ ३९४७ शेषवचनात्तु योऽसौ प्रत्यारम्भात्कृतो बहुव्रीहिः। ३९४८ तस्मात्सिध्यति तस्मिन्। ३९४९ प्रधानतो वा यतो वृत्तिः॥ ३९५० महदात्त्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्वचनं च नानाधिकरणार्थम्। ३९५१ अष्टनः कपाले हविषि। ३९५२ गवि च युक्ते॥

३। ४७ द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ८०८॥ ३९५३ प्राक् शतादिति वक्तव्यम्॥

३। ५० हृदयस्य हृल्लेखयदण्लासेषु ९८८॥ ३९५४ यदण्ग्रहणे (उत्तरपदाधिकारे प्रत्ययग्रहणे) रूपग्रहणं लेखग्रहणात्॥

३। ५२ पादस्य पदाज्यातिगोपहतेषु ९९०॥ ३९५५ पदादेशेऽन्तोदात्तनिपातनम्। ३९५६ पदोपहतार्थम्। ३९५७ उपदेशिवद्वचनं च स्वरसिद्ध्यर्थम्॥

३। ५३ पद्यत्यतदर्थे ९९१॥ ३९५८ पद्भाव इके चरतावुपसंख्यानम्॥

३। ५६ वा घोषमिश्रशब्देषु ९९४॥ ३९५९ निष्के चोपसंख्यानम्॥

३। ५७ उदकस्योदः संज्ञायाम् ९९५॥ ३९६० संज्ञायामुत्तरपदस्य च॥

३। ६१ इको ह्रस्वोऽङ्यो गालवस्य ९९९॥ ३९६१ इको ह्रस्वत्वमुत्तरपदमात्रे।

३९६२ सर्वान्ते हि लोकविज्ञानम् । ३९६३ इयङुवङ्व्ययप्रतिषेधः । ३९६४ अभ्रूकुंसादीनामिति वक्तव्यम् ॥

३ । ६६ खित्यनव्ययस्य २९४३ ॥ ३९६५ खिति ह्रस्वाप्रसिद्धिरनजन्तत्वात् । ३९६६ सिद्धं तु ह्रस्वान्तस्य मुम्वचनात् । ३९६७ संनियोगाद्वा ॥

३ । ६८ इच एकाचोऽम्प्रत्ययवच्च २९९४ ॥ ३९६८ अमः प्रत्ययवदनुदेशे प्रयोजनमात्वपूर्वसवर्णगुणेयङुवङादेशाः । ३९६९ अमः प्रत्ययवदनुदेश आत्वपूर्वसवर्णाप्रसिद्धिरप्रथमात्वात् । ३९७० सामान्यातिदेशे विशेषानतिदेशः । ३९७१ सिद्धं तु द्वितीयैकवचनवद्वचनात् । ३९७२ एकशेषनिर्देशाद्वा ॥

३ । ७० कारे सत्यागदस्य १००७ ॥ ३९७३ अस्तुसत्यागदस्य कारे । ३९७४ भक्षस्य च्छन्दसि । ३९७५ धेनोर्भव्यायाम् । ३९७६ लोकस्य पृणे । ३९७७ इत्येनभ्यासस्य । ३९७८ भ्राष्ट्राग्न्योरिन्धे । ३९७९ गिलेऽगिलस्य । ३९८० गिलगिले चेति वक्तव्यम् । ३९८१ उष्णभद्रयोः करणे । ३९८२ सूतोग्रराजभोजकुलमेरुभ्यो दुहितुः पुत्रड्वा ॥

३ । ७२ रात्रेः कृति विभाषा १००८ ॥ ३९८३ रात्रेरप्राति ॥

३ । ७३ नलोपो नञः ७५७ ॥ ३९८४ नञो नलोपेऽवक्षेपे तिङ्युपसंख्यानम् ॥

३ । ७८ सहस्य सः संज्ञायाम् १००९ ॥ ३९८५ सहस्य हलोपवचनम् । ३९८६ सादेशे हि स्वरे दोषः ॥

३ । ७९ ग्रन्थान्ताधिके च १०१० ॥ ३९८७ ग्रन्थान्ते वचनानर्थक्यमव्ययीभावेन कृतत्वात् ॥

३ । ८२ वोपसर्जनस्य ८४९ ॥ ३९८८ उपसर्जनस्य वावचने सर्वप्रसङ्गोऽविशेषात् । ३९८९ सिद्धं तु बहुव्रीहिनिर्देशात् ॥

३ । ८३ प्रकृत्याशिष्यगोवत्सहलेषु ८५० ॥ ३९९० प्रकृत्याशिष्यगवादिषु ॥

३ । ८६ चरणे ब्रह्मचारिणि १०१४ ॥ ३९९१ ब्रह्मण्युपपदे समानपूर्वे व्रते कर्मणि चरेर्णिनिर्व्रतलोपश्च ॥

३ । ८९ दृग्दृश्वतुषु १०१७ ॥ ३९९२ दृग्दृश्वतुषु दृक्ष उपसंख्यानम् ॥

३ । ९२ विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये ४१८ । ९५ सहस्य सध्रिः ४२२ ॥ ३९९३ अद्रिसध्र्योरन्तोदात्तवचनं कृत्स्वरनिवृत्त्यर्थम् । ३९९४ तत्र च्छन्दसि स्त्रियां प्रतिषेधः (बहुलम्) ॥

३ । ९३ समः समि ४२१ । ११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ १०३७ ॥ ३९९५ अञ्चतिनह्यादिषु क्विब्ग्रहणानर्थक्यं यस्मिन्विधिस्तदादावल्ग्रहणे ॥

३ । ९७ द्व्यन्तरुपसर्गेभ्योऽप ईत् ९४१ ॥ ३९९६ समाप ईत्त्वप्रतिषेधः । ३९९७ ईत्त्वमनवर्णादिति वक्तव्यम् ॥

३ । १०१ कोः कत्तत्पुरुषेऽचि १०२७ ॥ ३९९८ कद्भावे त्रावुपसंख्यानम् ॥

३ । १०९ पृषोदरादीनि यथोपदिष्टम् १०३४ ॥ ३९९९ दिक्शब्देभ्यस्तीरस्य तारभावे वा । ४००० वाचो वादे डत्वं वलभावश्चोत्तरपदस्येञि । ४००१ षष उत्त्वं दतृदशसूत्तरपदादेष्टुत्वं च । ४००२ धासु वा । ४००३ दुरो दाशनाशदभध्येषु । ४००४ स्वरो रोहतौ छन्दसि ॥

३ । १२१ इक्को वहेऽपीलोः १०४३ ॥ ४००५ अपील्वादीनामिति वक्तव्यम् ॥
३ । १२२ उपसर्गस्य घञ्यमनुष्ये बहुलम् १०४४ ॥ ४००६ अमनुष्यादाविति
वक्तव्यम् । ४००७ सादकारयोः कृत्रिमे । ४००८ प्रतिवेशादीनां विभाषा ॥
३ । १३९ संप्रसारणस्य १००४ ॥ ४००९ इकः ह्रस्वत्वसंप्रसारणदीर्घत्वं विप्रतिषेधेन ॥
४ । १ अङ्गस्य २०० ॥ ४०१० अङ्गस्येति स्थानषष्ठी चेत्तच्चन्म्यन्तस्य चाधिकारः ।
४०११ अवयवषष्ठ्यादीनां चाप्रसिद्धिः । ४०१२ सिद्धं तु परस्परं प्रत्यङ्गप्रत्ययसंज्ञाभावात् ।
४०१३ संबन्धषष्ठीनिर्देशश्च । ४०१४ अङ्गाधिकारस्य प्रयोजनं संप्रसारणदीर्घत्वे । ४०१५
नाम्नोश्च । ४०१६ लिङ्यत्वे । ४०१७ अतो भिस ऐस्त्वे । ४०१८ लुङादिष्वडाटौ ।
४०१९ इयङुवङ्गुणमस्मत्ततङाभिनुडानेमुक्ह्रस्वयिदीर्घमितत्वानि । ४०२० अर्थवद्ग्रहण-
प्रत्ययग्रहणाभ्यां सिद्धम् ॥
४ । २ हलः २५५३ ॥ ४०२१ अण्प्रकरणादकारस्याप्राप्तिः । ४०२२ इग्ग्रहणस्य चाणिव-
शेषणत्वात् ॥
४ । ३ नामि २०९ ॥ ४०२३ नामि दीर्घ आमि चेत्कृते दीर्घे न नुड्भवेत् । ४०२४ वच-
नाद्यत्र तन्नास्ति । ४०२५ नोपधायाश्च चर्मणाम् ॥
४ । १२-१३ इन्हन्पूषार्यम्णां शौ ३५६ । सौ च ३५७ ॥ ४०२६ हनः क्वावुपधादीर्घत्व-
प्रसङ्गः । ४०२७ नियमवचनात्सिद्धम् । ४०२८ नियमवचनात्सिद्धमिति चेत्सर्वनामस्थानप्रक-
रणे नियमवचनादन्यत्र नियमः । ४०२९ दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति
सुविद्वान् । ४०३० शौ नियमं पुनरेव विदध्यात् । ४०३१ भ्रूणहनीति तथास्य दुष्येत् ।
४०३२ शास्मि निवर्त्य सुटीत्यविशेषे शौ नियमं कुरु वाप्यसमीक्ष्य । ४०३३ दीर्घविधेरु-
पधानियमान्मे हन्त यि दीर्घविधौ च न दोषः ॥ ४०३४ सुट्यपि प्रकृतेऽनवकाशः शौ नि-
यमोऽप्रकृतप्रतिषेधे । ४०३५ यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम् ॥
४ । १४ अत्वसन्तस्य चाधातोः ४२९ ॥ ४०३६ अत्वसन्तस्य दीर्घत्वे पित उप
संख्यानम् ॥
४ । १६ अज्झनगमां सनि २६१४ ॥ ४०३७ गमेर्दीर्घत्व इङ्ग्रहणम् । ४०३८ अग्रहणे
ह्यनादेशस्यापि दीर्घप्रसङ्गः । ४०३९ न वा छन्दस्यनादेशस्यापि दीर्घत्वदर्शनादिङ्ग्रहणानर्थ-
क्यम् । ४०४० सनि दीर्घ उपधाधिकारश्चेद्व्यञ्जनप्रतिषेधः ॥
४ । १९ च्छ्वोः शूडनुनासिके च २५६१ ॥ ४०४१ शूट्त्वे क्ङिदधिकारश्चेच्छः षत्वम् ।
४०४२ तुक्प्रसङ्गश्च । ४०४३ निवृत्ते दिव ऊड्भावः । ४०४४ तदर्थं तपरः कृतः ॥
४ । २२ असिद्धवदत्राभात् २१८३ ॥ ४०४५ अत्रग्रहणं विषयार्थम् । ४०४६ प्रयोजनं
शैत्त्वं धित्वे । ४०४७ हिलोप उत्त्वे । ४०४८ नास्तिलोपेण्यणादेशा अडाड्विधौ । ४०४९
अनुनासिकलोपो हिलोपाल्लोपयोर्जभावश्च । ४०५० संप्रसारणमवर्णलोपे । ४०५१ रेभाव-
आल्लोपे । ४०५२ उत्तु कृञः कथमोर्विनिवृत्तौ । ४०५३ णेरपि चेट्टि कथं विनिवृत्तिः ।
४०५४ अब्रुवतस्तव योगमिमं स्याल्लुक् चिणो नु कथं न तरस्य ॥ ४०५५ चं भगवा-
न्कृतवांस्तु तदर्थं तेन भवेदिटि णोर्विनिवृत्तिः । ४०५६ म्वोरपि ये च तथाप्यनुवृत्तौ ।
४०५७ चिण्लुकि च क्ङित एव हि लुक्स्यात् ॥ ४०५८ सिद्धं वसुप्रसारणमज्विधौ । ४०५९

बहिरङ्गलक्षणत्वादसिद्धत्वाच्च । ४०६० समानाश्रयवचनात्सिद्धम् । ४०६१ ह्रस्वयलोपाल्लो-पाश्रयादेशे ल्यपि । ४०६२ वुग्युटावुवङ्यणोः । ४०६३ प्राग्भादिति चेच्छुनामघोनाभ्रूगुणेष्वुप-संख्यानम् । ४०६४ आभादिति चेद्भ्रुप्रसारणयलोपप्रस्थादीनां प्रतिषेधः ॥

४ । ३४ अनिदितां हल उपधायाः क्ङिति ४१९ ॥ ४०६५ अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसंख्यानम् । ४०६६ बृंहेरच्यनिटि । ४०६७ रञ्जेर्णौ मृगरमणे । ४०६८ घिनुणि च । ४०६९ रजकरजनरजःसूपसंख्यानम् ॥

२ । ३४ शास इदङ्हलोः ३४८ ॥ ४०७० शास इत्व आशासः क्वौ ॥

४ । ३७ अनुदात्तोपदेश वनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति २४२८ ॥ ४०७१ अनुदात्तोपदेशेऽनुनासिकलोपो ल्यपि च । ४०७२ वामः ॥

४ । ४० गमः क्वौ २९८६ ॥ ४०७३ गमादीनामिति वक्तव्यम् । ४०७४ ऊङ् च ॥

४ । ४२ जनसनखनां सञ्झलोः २५०४ ॥ ४०७५ सनोतेरनुदात्तलोपादात्त्वं विप्रतिषेधेन ॥

४ । ४६ आर्धधातुके २३०७ ॥ ४०७६ अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् । ४०७७ आल्लोप ईत्त्वमेत्त्वं च चिण्वद्भावश्च सीयुटि ॥

४ । ४७ भ्रस्जो रोपधयोरमन्यतरस्याम् २५३९ ॥ ४०७८ भ्रस्जादेशात्संप्रसारणं विप्रतिषेधेन । ४०७९ रसोर्वचने सिचि वृद्धेर्भ्रस्जादेशः ॥

४ । ४८ अतो लोपः २३०८ ॥ ४०८० ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् ॥

४ । ४९ यस्य हलः २६३१ ॥ ४०८१ यलोपे वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधः । ४०८२ संघातग्रहणं चेत्क्यस्य विभाषायां दोषः । ४०८३ आदेः परवचनात्सिद्धम् ॥

४ । ५२ निष्ठायां सेटि ३०५७ ॥ ४०८४ निष्ठायां सेड्ग्रहणमनिटि प्रतिषेधार्थम् । ४०८५ निष्ठायां सेड्ग्रहणमनिटि प्रतिषेधार्थमिति चेत्तत्सिद्धमनिडभावात् । ४०८६ एकाचो हि प्रतिषेधः । ४०८७ इड्भावार्थं तु तन्निमित्तत्वल्लोपस्य । ४०८८ अवचने हि णिलोप इट्प्रतिषेधप्रसङ्गः । ४०८९ वृधिरमिशृधीनामुपसंख्यानं सार्वधातुकत्वात् ॥

४ । ५५ अयामन्ताल्वाय्येत्न्विष्णुषु २३११ ॥ ४०९० क्त्नाविटि णेर्गुणवचनम् । ४०९१ इत्नौ प्रत्ययान्तरकरणम् । ४०९२ अयादेशे चोपसंख्यानम् ॥

४ । ५६ ल्यपि लघुपूर्वस्य ३३३६ ॥ ४०९३ ल्यपि लघुपूर्वस्येति चेद्व्यञ्जनान्तेषूपसंख्यानम् ४०९४ अल्लोपे च गुरुपूर्वात्प्रतिषेधः । ४०९५ ल्यपि लघुपूर्वादिति वचनात्सिद्धम् ॥

४ । ५७ विभाषापः ३३३७ ॥ ४०९६ इङादेशस्य प्रतिषेधो वक्तव्यः । ४०९७ आपः सानुबन्धकनिर्देशादिङि सिद्धम् ॥

४ । ६२ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च २७५७ ॥ ४०९८ वृद्धिश्चिण्वद्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति । ४०९९ इड्वासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती । ४१०० चिण्वद्भाव उपदेशवचनमृकारगुणबलीयस्त्वात् । ४१०१ वधिभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन । ४१०२ हनिणिङादेशप्रतिषेधश्च । ४१०३ अङ्गस्येति तु प्रकरणादाङ्गशास्त्रातिदेशात्सिद्धम् ॥

४ । ६४ आतो लोप इटि च २३७२ ॥ ४१०४ इड्ग्रहणमक्किदर्थम् । ४१०५ सार्वधातुके यादीत्यार्धधातुकाधिकारादुपसंख्यानम् ॥

४ । ६६ घुमास्थागापाजहातिसां हलि २४६२ ॥ ४१०६ ईत्वे वकारप्रतिषेधो घृतं घृतपावान इति दर्शनात् ॥

४ । ७४ न माङ्योगे २२२८ ॥ ४१०७ अजादीनामटा सिद्धम् । ४१०८ वृद्ध्यर्थमिति चेदटः । ४१०९ अस्वपो हसतीत्यत्र । ४११० धातौ वृद्धिमटः स्मरेत् ॥ ४१११ पररूपं गुणे नाटः । ४११२ ओमाङोरुसि तत्समम् । ४११३ छन्दोर्थे बहुलं दीर्घम् । ४११४ इणस्त्यो-रन्तरङ्गतः ॥

४ । ७७ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ २७१ ॥ ४११५ इयङादिप्रकरणे तन्वादीनां छन्दसि बहुलम् ॥

४ । ८२ एरनेकाचोऽसंयोगपूर्वस्य २७२ ॥ ४११६ यणादेशः स्वरपदपूर्वोपधस्य च । ४११७ असंयोगपूर्वे ह्यनिष्टप्रसङ्गः ॥

४ । ८४ वर्षाभ्वश्च २८२ ॥ ४११८ वर्षादन्कारपुनःपूर्वस्य भुव इति वक्तव्यम् ॥

४ । ८७ हुश्नुवोः सार्वधातुके २३८७ ॥ ४११९ हुभ्रुग्रहणानर्थक्यमन्यस्याभावात् । ४१२० यङ्लुगर्थम् । ४१२१ यङ्लुगर्थमिति चेदार्धधातुकत्वात्सिद्धम् ॥

४।८९ ऊदुपधाया गोहः २३६४ ॥ ४१२२ गोहिग्रहणं विषयार्थम् । ४१२३ अयादेशप्रतिषेधार्थं च । ४१२४ ह्रस्वादेशे ह्ययादेशप्रसङ्ग ऊत्त्वस्यासिद्धत्वात् ॥

४ । ९० दोषो णौ २६०४ ॥ ४१२५ दोषिग्रहणे च ॥

४ । ९३ चिण्णमुलोर्दीर्घोऽन्यतरस्याम् २७६२ ॥ ४१२६ चिण्णमुलोर्णिव्यपेतानां यङ्लोपे च । ४१२७ चिण्णमुलोर्णिव्यपेतानां यङ्लोपे चान्तरङ्गलक्षणत्वात्सिद्धम् ॥

४ । ९६ छादेर्घेऽद्व्युपसर्गस्य ३२९७ ॥ ४१२८ अद्विप्रभृत्युपसर्गस्येति वक्तव्यम् । ४१२९ न वा एष लोके संप्रत्ययः ॥

४ । १०० घसिभसोर्हलि च ३५५० ॥ ४१३० हल्ग्रहणमनर्थकमन्यत्रापि दर्शनात् ॥

४ । १०१ हुझल्भ्यो हेर्धिः २४२५ ॥ ४१३१ हेर्धित्वे हलधिकारादिटोऽप्रतिषेधः ॥

४ । १०४ चिणो लुक् २३२९ ॥ ४१३२ चिणो लुकि तग्रहणम् । ४१३३ चिणो लुकि तग्रहणानर्थक्यं संघातस्याप्रत्ययत्वात् । ४१३४ तलोपस्य चासिद्धत्वात् । ४१३५ कार्यकृतत्वाद्वा ॥

४ । १०६ उतश्च प्रत्ययादसंयोगपूर्वात् २३३४ ॥ ४१३६ उतश्च प्रत्ययाच्छन्दोवावचनम् । ४१३७ उत्तरार्थं च ॥

४ । ११० अत उत्सार्वधातुके २४६७ ॥ ४१३८ स्यान्तस्य प्रतिषेधो वक्तव्यः । ४१३९ कृञ उत्त्वे उकारान्तनिर्देशात्स्यान्तस्याप्रतिषेधः । ४१४० अनुप्रयोगे तु भुवास्त्यबाधनं स्मरन्ति कर्तुर्वचनान्मनीषिणः । ४१४१ लोपे द्विर्वचनासिद्धिः । ४१४२ स्थानिवदिति चेत्कृते भवेद्द्वित्वे । ४१४३ नैवं सिध्यति कस्मात्प्रत्यङ्गत्वाद्भवेद्धि पररूपम् । ४१४४ तस्मिंश्च कृते लोपः । ४१४५ दीर्घत्वं बाधकं भवेत्तत्र ॥

४ । ११४ इद्दरिद्रस्य २४८२ ॥ ४१४६ दरिद्रातेरार्धधातुके लोपः । ४१४७ सिद्धश्च प्रत्ययविधौ । ४१४८ वाद्यतन्याम् ॥

४ । १२० अत एकहल्मध्येऽनादेशादेर्लिटि २२६० ॥ ४१४९ पकारणकारादेशादेरेत्त्ववचनं लिटि । ४१५० फलिभजिग्रहणं तु ज्ञापकमभ्यासादेशासिद्धत्वस्य । ४१५१ प्रथमतृतीयादीनामादेशादित्वादेत्त्वाभावः । ४१५२ न वा शसिदद्योः प्रतिषेधो ज्ञापको रूपाभेद एत्त्वविज्ञानस्य । ४१५३ दम्भ एत्त्वम् । ४१५४ नलोपस्यासिद्धत्वात् । ४१५५ नशिमन्योरलिटयेत्त्वम् । ४१५६ छन्दस्यमिपचोरपि । ४१५७ अनेशं मेनकेत्येतद्द्वेमानं लिङि पेचिरन् ॥ ४१५८ यजायेजे वपावेपे दम्भ एत्त्वमलक्षणम् । ४१५९ श्रसोरत्त्वे तकारेण ज्ञाप्यते त्वेत्वशासनम् ॥

४ । १२१ थलि च सेटि २२६१ ॥ ४१६० थल्ग्रहणमक्किदर्थम् ॥

४ । १२३ राधो हिंसायाम् २५३२ ॥ ४१६१ राधादिषु स्थानिनिर्देशः ॥

४ । १२७-१२८ अर्वणस्त्रसावनञः ३६४ । मघवा बहुलम् ३६० ॥ ४१६२ अर्वणस्तृ मघोनश्च न शिष्यं छान्दसं हि तत् । ४१६३ मतुब्वन्योर्विधानाच्च । ४१६४ छन्दस्युभयदर्शनात् ॥

४ । १३० पादः पत् ४१४ ॥ ४१६५ पाद उपधाह्रस्वत्वम् । ४१६६ आदेशे हि सर्वादेशप्रसङ्गः । ४१६७ न वा निर्दिश्यमानस्यादेशत्वात् । ४१६८ प्रयोजनं सुतिङादेशे । ४१६९ ल्यब्भावे च । ४१७० त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च । ४१७१ उदः पूर्वत्वे ॥

४ । १३२ वाह ऊठ् ३२९ ॥ ४१७२ वाह ऊठ्वचनानर्थक्यं संप्रसारणेन कृतत्वात् । ४१७३ गुणः प्रत्ययलक्षणत्वात् । ४१७४ एज्ग्रहणाद्वृद्धिः ॥

४ । १३५ षपूर्वहन्धृतराज्ञामणि ११६० ॥ ४१७५ षपूर्वादीनां पुनर्वचनमल्लोपार्थम् । ४१७६ अवधारणे ह्यन्यत्र प्रकृतिभाव उपधालोपप्रसङ्गः ॥

४ । १४० आतो धातोः २४० ॥ ४१७७ आतोऽनापः ॥

४ । १४१ मन्त्रेष्वाङ्यादेरात्मनः ३५५४ ॥ ४१७८ मन्त्रेष्वात्मनः प्रत्ययमात्रप्रसङ्गः । ४१७९ छान्दसत्वात्सिद्धम् । ४१८० आदिग्रहणानर्थक्यं चाकारप्रकरणात् ॥

४ । १४३ टेः ३१६ ॥ ४१८१ अभस्योपसंख्यानम् । ४१८२ डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् ॥

४ । १४४ नस्तद्धिते ६७९ ॥ ४१८३ नकारान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् । ४१८४ चर्मणः कोशे । ४१८५ अश्मनो विकारे । ४१८६ शुनः संकोचे । ४१८७ अव्ययानां च । ४१८८ सायंप्रातिकाद्यर्थम् ॥

४ । १४८ यस्येति च ३११ ॥ ४१८९ यस्येत्यादौ श्यां प्रतिषेधः । ४१९० इयङुवङ्भ्यां लोपो विप्रतिषेधेन । ४१९१ गुणवृद्धी च । ४१९२ न वेयङुवङ्देशस्यान्याविषये वचनात् । ४१९३ तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधः ॥

४ । १४९ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ४९९ ॥ ४१९४ सूर्यादीनामनन्तेऽप्रसिद्धिरङ्गान्यत्वात् । ४१९५ सिद्धं तु स्थानिवत्प्रतिषेधात् । ४१९६ उपधाग्रहणानर्थक्यं च । ४१९७ विषयपरिगणनं च । ४१९८ सूर्यमत्स्ययोर्ङ्याम् । ४१९९ सूर्यागस्त्ययोश्छे च । ४२०० तिष्यपुष्ययोर्नक्षत्राणि । ४२०१ अन्तिकस्य तसि कादिलोप आद्युदात्तत्वं च

४२०२ तमे तादेश्च । ४२०३ तसीत्येव न वक्तव्यो दृष्टो दाशतयेऽपि हि । ४२०४ यौ लोपोऽन्तिषदित्यत्र । ४२०५ तथायौ येऽन्त्यथर्वसु ॥

४ । १५४ तुरिष्ठेमेयःसु २००८ ॥ ४२०६ तुः सर्वलोपविज्ञानमन्त्यस्य वचनानर्थक्यात् । ४२०७ विजयिष्ठकरिष्ठयोर्गुणदर्शनात् ॥

४ । १५५ टेः १७८६ ॥ ४२०८ णाविष्ठवत्प्रातिपदिकस्य । ४२०९ पुंवद्भावरभावटिलोपयणादिपरार्थम् । ४२१० 'णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरप्रादिविन्मतोर्लुक्कन्विध्यर्थम्' इति भारद्वाजीयाः ॥

४ । १६१ र ऋतो हलादेर्लघोः १७८९ ॥ ४२११ पृथुमृदुकृशभृशदृढपरिवृढानामिति वक्तव्यम् ॥

४ । १६३ प्रकृत्यैकाच् २०१० ॥ ४२१२ प्रकृत्यैकाजिष्ठेमेयःसु चेदेकाच उच्चारणसामर्थ्यादवचनात्प्रकृतिभावः । ४२१३ विन्मतोस्तु लुगर्थम् । ४२१४ प्रकृत्याके राजन्यमनुष्ययुवानः ॥

४ । १७० न मपूर्वोऽपत्येऽवर्मणः ११५७ ॥ ४२१५ मपूर्वात्प्रतिषेधे वा हितनाम्नः ।

४ । १७१ ब्राह्मोऽजातौ ११५८ ॥ ४२१६ ब्राह्मस्याजातौ लोपार्थं वचनम् । ४२१७ तत्राप्राप्तविधाने प्राप्तप्रतिषेधः । ४२१८ न वा पर्युदाससामर्थ्यात् ॥

४ । १७४ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ११४५ ॥ ४२१९ भ्रौणहत्ये तत्वनिपातनानर्थक्यं सामान्येन कृतत्वात् । ४२२० ज्ञापकं तु तद्धिते तत्वप्रतिषेधस्य । ४२२१ ऐक्ष्वाकस्य स्वरभेदान्निपातनं पृथक्त्वेन । ४२२२ एकश्रुत्या निर्देशात्सिद्धम् । ४२२३ मैत्रेये ढञि यादिलोपनिपातनम् । ४२२४ हिरण्मये यलोपवचनम् । ४२२५ हिरण्ययस्य च्छन्दसि मलोपवचनात्सिद्धम् ॥

इति षष्ठोऽध्यायः ।

सप्तमोऽध्यायः ।

१ । १ युवोरनाकौ १२४७ ॥ ४२२६ युवोरनाकाविति चेद्धातुप्रतिषेधः । ४२२७ भुज्व्यादीनां च । ४२२८ अनुनासिकपरत्वात्सिद्धम् । ४२२९ तत्र ङीब्नुमोः प्रतिषेधः । ४२३० धात्वन्तस्य च । ४२३१ षिड्टिट्ग्रहणं तु ज्ञापकमुगित्कार्याभावस्य । ४२३२ न वा षित्करणं ङीब्विधानार्थम् । ४२३३ टित्करणमनुपसर्जनार्थम् । ४२३४ विप्रतिषेधात्तु टापो बलीयस्त्वम् । ४२३५ धात्वन्तस्य चार्थवत्त्वात् । ४२३६ नुम्विधौ झल्ग्रहणम् । ४२३७ लिङ्गविशिष्टप्रतिषेधार्थम् । ४२३८ न वा विभक्तौ लिङ्गविशिष्टाग्रहणम् । ४२३९ प्रयोजनं शुनः स्त्रे । ४२४० यूनः संप्रसारणे । ४२४१ उगिदचां नुम्विधौ । ४२४२ अनडुहश्चाम्विधौ । ४२४३ पथिमथोरात्त्वे । ४२४४ पुंसोऽसुङ्विधौ । ४२४५ सख्युर्णित्त्वानङौ । ४२४६ भवद्भगवदघवतामोद्भावे । ४२४७ सिद्धं तु युवोरनुनासिकत्वात् ॥

१ । २ आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ४७५ ॥ ४२४८ आयनादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थम् । ४२४९ न वा क्वचिच्चित्करणादुपदेशिवद्वचनानर्थक्यम् ।

४२५० तत्रोणादिप्रतिषेधः । ४२५१ धातोर्वेयङ्वचनात् । ४२५२ प्रातिपदिकविज्ञानाच्च पाणिनेः सिद्धम् ॥

१ । ३ झोऽन्तः २१६१ ॥ ४२५३ झादेशे धात्वन्तप्रतिषेधः । ४२५४ प्रत्ययाधिकारात्सिद्धम् । ४२५५ प्रत्ययाधिकारात्सिद्धमिति चेदनादेशवचनम् । ४२५६ असमासनिर्देशात्सिद्धम् । ४२५७ तत्र शयान्ता इत्यनकारान्तत्वादङ्गस्याद्भावप्रतिषेधः । ४२५८ सिद्धमनानन्तर्यादनकारान्तेनाद्भावनिवृत्तिः । ४२५९ तत्र रुटि सांनियोगवचनात्सिद्धम् ॥

६ शीङो रुट् २४४२ ॥ ४२६० रुटि दृशिगुणप्रतिषेधः । ४२६१ पूर्वान्ते शीङो गुणविधिः । ४२६२ झादेशादाड्विटि । ४२६३ न वा नित्यत्वादाटः । ४२६४ अन्तरङ्गलक्षणत्वाच्च ॥

१ । ९ अतो भिस ऐस् २०३ ॥ ४२६५ एत्त्वं भिसि परत्वाचेदत ऐस्क भविष्यति । ४२६६ कृत ऐत्त्वे भौतपूर्व्यात् । ४२६७ ऐस्तु नित्यस्तथा सति ॥

१ । १४ सर्वनाम्नः स्मै २१५ ॥ ४२६८ अश एकादिष्टात्स्मायादीनामुपसंख्यानम् । ४२६९ न वा बहिरङ्गलक्षणत्वात् ॥

१ । २१ अष्टाभ्य औश् ३७२ ॥ ४२७० औशयौ ॥ ४२७१ अस्तु लुक्तत्र । ४२७२ षड्भ्योऽप्यैत्वं प्रसज्यते । ४२७३ अपवादः । ४२७४ यस्य विषये । ४२७५ यो वा तस्मादनन्तरः ॥ ४२७६ आत्वं यत्र तु तत्रौत्त्वम् । ४२७७ तथा ह्यस्य ग्रहः कृतः ॥

१ । २३ स्वमोर्नपुंसकात् ३१९ ॥ ४२७८ स्वमोर्लुक् त्यदादिभ्यश्च । ४२७९ कृते ह्यत्वे न लुग्भवेत् । ४२८० शिशीलुग्नुम्विधिषु नपुंसकग्रहणं शब्दग्रहणं चेदन्यपदार्थे प्रतिषेधः । ४२८१ सिद्धं तु प्रकृतार्थविशेषणत्वात् । ४२८२ अस्थ्यादिषु शब्दग्रहणम् ॥

१ । २५ अद्ड्डतरादिभ्यः ३१५ ॥ ४२८३ अद्धात्वे पूर्वसवर्णप्रतिषेधः । ४२८४ सिद्धमनुनासिकोपधत्वात् । ४२८५ टुक्करणाद्वा । ४२८६ डित्करणाद्वा ॥

१ । २६ नेतराच्छन्दसि ३५५९ ॥ ४२८७ इतराच्छन्दसि प्रतिषेध एकतरात्सर्वत्र । ४२८८ नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेन ॥

१ । २७ युष्मदस्मद्भ्यां ङसोऽश् ३३९ ॥ ४२८९ ङस आदेशे शित्करणानर्थक्यमकारस्याकारवचनानर्थक्यात् । ४२९० अर्थवत्त्वादेशे लोपार्थम् । ४२९१ तस्माच्छित्करणम् ॥

१ । ३३ साम आकम् ४०० ॥ ४२९२ साम्ग्रहणं यथागृहीतस्यादेशवचनात् । ४२९३ न वा द्विपर्यन्तानामकारवचनादामि सकाराभावः । ४२९४ सुट्प्रतिषेधस्त्वादेशे लोपविज्ञानात् । ४२९५ न वा टिलोपवचनादादेशे टाप्प्रतिषेधार्थम् । ४२९६ न वा लिङ्गाभावाट्टिलोपवचनानर्थक्यम् । ४२९७ तस्मात्सुट्प्रतिषेधः ॥

१ । ३६ विदेः शतुर्वसुः ३१०५ ॥ ४२९८ विदेर्वसोः कित्त्वम् ॥

१ । ३७ समासेऽनञ्पूर्वे क्त्वो ल्यप् ३३३२ ॥ ४२९९ ल्यबादेश उपदेशिवद्वचनम् । ४३०० अनादिष्टार्थम् । ४३०१ बहिरङ्गलक्षणत्वात् । ४३०२ स्नात्वाकालकादिषु च प्रतिषेधः । ४३०३ तदन्तनिर्देशात्सिद्धम् । ४३०४ समासनिपातनाद्वा । ४३०५ अनञो वा परस्य ॥

१ । ३९ सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ३५६१ ॥ ४३०६ सुपां च

सुपो भवन्तीति वाच्यम् । ४३०७ तिङां च तिङो भवन्तीति वाच्यम् । ४३०८ इयाडि-याजीकाराणामुपसंख्यानम् । ४३०९ आङ्याजयारां चोपसंख्यानम् ॥

१ । ४० अमो मश् ३५६२ ॥ ४३१० अमो मश मकारस्य । ४३११ वचनादन्यबाधनम् । ४३१२ द्विमकार ईडपृक्ते । ४३१३ यकारादौ न दुष्यति ॥

१ । ५१ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि २६६२ ॥ ४३१४ अश्ववृषयोर्मैथुनेच्छायाम् । ४३१५ क्षीरलवणयोर्लालसायाम् । ४३१६ सर्वप्रातिपदिकेभ्यो लालसायामिति । ४३१७ वक्तव्यं दध्यस्यति मध्वस्यतीत्येवमर्थम् । ४३१८ सुग्वक्तव्यो दधिस्यति मधुस्यतीत्येवमर्थम् ॥

१ । ५८ इदितो नुम्धातोः २२६२ ॥ ४३१९ नुम्विधावुपदेशिवद्वचनं प्रत्ययविध्यर्थम् । ४३२० इतरथा ह्यनकारे प्रत्ययः । ४३२१ तत्रायथेष्टप्रसङ्गः । ४३२२ धातुग्रहणसामर्थ्याद्वा तदुपदेशे नुम्विधानम् ॥

१ । ५९ शे मुचादीनाम् २५४२ ॥ ४३२३ शे तृम्फादीनाम् । ४३२४ लुप्तनकारत्वात् ॥

१ । ६८ न सुदुर्भ्यां केवलाभ्याम् ३३०७ ॥ ४३२५ सुदुरोः केवलग्रहणमन्योपसर्गप्रतिषेधार्थम् ॥

१ । ६९ विभाषा चिण्णमुलोः २७६५ ॥ ४३२६ चिण्णमुलोरनुपसर्गस्य ॥

१ । ७० उगिदचां सर्वनामस्थानेऽधातोः ३६१ ॥ ४३२७ उगित्यञ्चतिग्रहणात्सिद्धमधातोः ॥

१ । ७२ नपुंसकस्य झलचः ३१४ ॥ ४३२८ झलचो नुम्विधावुगित्प्रतिषेधः । ४३२९ विप्रतिषेधात्सिद्धम् । ४३३० पुनःप्रसङ्ग इति चेदमादिभिस्तुल्यम् । ४३३१ तत्र बहूर्जि प्रतिषेधः । ४३३२ अन्त्यात्पूर्वं नुममेके ॥

१ । ७३ इकोऽचि विभक्तौ ३२० ॥ ४३३३ इकोऽचि व्यञ्जने मा भूत् । ४३३४ अस्तु लोपः । ४३३५ स्वरः कथम् । ४३३६ स्वरो वै श्रूयमाणेऽपि । ४३३७ लुप्ते किं न भविष्यति ॥ ४३३८ इकोऽचि विभक्तावज्ग्रहणं नुम्नुटोर्विप्रतिषेधार्थम् । ४३३९ इतरथा हि नुमो नित्यनिमित्तत्वान्नुडभावः । ४३४० उत्तरार्थं च ॥

१ । ७४ तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ३२१ ॥ ४३४१ पुंवदिति नुम्प्रतिषेधश्चेद्गुणनाभावनुडौत्त्वप्रतिषेधः । ४३४२ ह्रस्वाभावार्थं च । ४३४३ अर्थातिदेशात्सिद्धम् । ४३४४ तद्धितलुक्प्रतिषेधश्च । ४३४५ न वा समानायामाकृतौ भाषितपुंस्कविज्ञानात् ॥

१ । ८२ सावनडुहः ३३२ ॥ ४३४६ अनडुहः सावाम्प्रतिषेधो नुमोऽनवकाशत्वात् । ४३४७ न वावर्णोपधस्य नुम्वचनात् । ४३४८ पुनः प्रसङ्गविज्ञानाद्वा सिद्धम् । ४३४९ यथात्वादिषु द्विर्वचनम् ॥

१ । ८४ दिव औत् ३३६ ॥ ४३५० दिव औत्त्वे धातुप्रतिषेधः । ४३५१ अधात्वधिकारात्सिद्धम् । ४३५२ अधात्वधिकारात्सिद्धमिति चेन्नपुंसके दोषः ॥

१ । ८६ इतोऽत्सर्वनामस्थाने ३६६ ॥ ४३५३ इतोऽद्वचनमाकारप्रकरणात् । ४३५४ षपूर्वार्थं तु ॥

१ । ८९ पुंसोऽसुङ् ४३६ ॥ ४३५५ असुङ्ङ्युपदेशिवद्वचनं स्वरसिद्ध्यर्थं बहिरङ्गलक्षणत्वात् ॥

१ । ९० गोतो णित् २८४ ॥ ४३५६ गोतः सर्वनामस्थाने णित्कार्यातिदेशः । ४३५७ सर्वनामस्थाने णित्त्ववचने ह्यसंप्रत्ययः षष्ठ्यनिर्देशात् । ४३५८ तपरकरणमनर्थकं स्थानिवत्प्रतिषेधात् । ४३५९ इतरथा हि संबुद्धिजसोः प्रतिषेधः ॥

१ । ९५-९६ तृज्वत्क्रोष्टुः २७४ । स्त्रियां च ३०५ ॥ ४३६० तृज्वत्स्त्रियां विभक्तौ चेत्क्रोष्ट्रीभक्तिर्न सिध्यति । ४३६१ ईकारे तन्निमित्तः सः । ४३६२ गौरादिषु न पच्यते ॥ ४३६३ तेनैव भावनं चेत्स्यादानिष्टोऽपि प्रसज्यते । ४३६४ तृज्वदिति शास्त्रातिदेशश्चेयथा त्रिणि तद्वत् । ४३६५ तत्र रपरवचनम् । ४३६६ रूपातिदेश इति चेत्सर्वादेशप्रसङ्गः । ४३६७ सिद्धं तु रूपातिदेशात् । ४३६८ सिद्धं तु प्रत्ययग्रहणे यस्मात्स विहितस्तदादितदन्तविज्ञानात् । ४३६९ आन्तरतम्याच्च सिद्धम् । ४३७० तृज्वद्वचनमनर्थकं तृज्विषये तृचो मृगवान्नित्वात् । ४३७१ तुनो निवृत्त्यर्थमिति चेत्सिद्धं यथान्यत्रापि । ४३७२ वावचनानर्थक्यं च स्वभावसिद्धत्वात् । ४३७३ गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् । ४३७४ नुमाचिरतृज्वद्भावेभ्यो नुट् । ४३७५ न वा नुड्विषये रप्रतिषेधात् । ४३७६ इतरथा हि सर्वापवादः । ४३७७ तस्मान्नुड्विषये रप्रतिषेधः ॥

१ । ९८ चतुरनडुहोरामुदात्तः ३३१ ॥ ४३७८ आमनडुहः स्त्रियां वा ॥

१ । १००-१०२ ऋत इद्धातोः २३९० । उपधायाश्च २५७१ । उदोष्ठ्यपूर्वस्य २४९४ ॥ ४३७९ इत्त्वोत्त्वाभ्यां गुणवृद्धी विप्रतिषेधेन ॥

२ । १ सिचि वृद्धिः परस्मैपदेषु २२९७ ॥ ४३८० सिचि वृद्धावोकारप्रतिषेधः । ४३८१ ओकाराद्वृद्धिर्विप्रतिषेधेन । ४३८२ ओकाराद्वृद्धिर्विप्रतिषेधेनेति चेदोत्त्वाभावः । ४३८३ पुनः प्रसङ्गविज्ञानाद्वा सिद्धम् । ४३८४ यथा प्रसारणादिषु द्विर्वचनम् । ४३८५ सौढामित्रौ बहिरङ्गलक्षणत्वात्सिद्धम् ॥

२ । ३ वदव्रजहलन्तस्याचः २२६७ ॥ ४३८६ हल्ग्रहणमिटि प्रतिषेधार्थम् । ४३८७ न वानन्तरप्रतिषेधात् । ४३८८ तच्चानन्त्यार्थम् । ४३८९ अन्त्यस्य वचनानर्थक्यम् । ४३९० अतो विभाषार्थमिति चेत्सिद्धं वृद्धेर्लोपबलीयस्त्वात् । ४३९१ एकाचस्तौ बलीति वा ॥

२ । ८ नेड्वशि कृति २९८१ ॥ ४३९२ नेड्रमनादौ कृति ॥

२ । ९ तितुत्रतथसिसुसरकसेषु च ३१६३ ॥ ४३९३ तितुत्रेष्वग्रहादीनाम् ॥

२ । १० एकाच उपदेशेऽनुदात्तात् २२४६ ॥ ४३९४ एकाज्ग्रहणं जागर्त्यर्थम् । ४३९५ वध इट्प्रतिषेधः संनिपात एकाच्त्वात्प्रकृतेश्चानुदात्तत्वात् । ४३९६ एकाच उपदेशेऽनुदात्तादित्युपदेशवचनमनुदात्तविशेषणं चेत्कृञादिभ्यो लिटि नियमानुपपत्तिरप्राप्तत्वात्प्रतिषेधस्य । ४३९७ तत्र पचादिभ्य इड्वचनम् । ४३९८ सनश्चेट्प्रतिषेधः । ४३९९ उभयविशेषणत्वात्सिद्धम् । ४४०० यङ्लोपे च तदन्तद्विर्वचनात् ॥

२ । १३ कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि २२९३ ॥ ४४०१ कृञोऽसुटः ॥

२ । १४ श्वीदितो निष्ठायाम् ३०३९ ॥ ४४०२ श्विग्रहणमिदन्तत्वादुपदेशस्य ॥

२ । १५ यस्य विभाषा ३०२५ ॥ ४४०३ यस्य विभाषाविदेः ॥

२ । १८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ३०५८ ॥ ४४०४ क्षुब्धं मन्थाभिधाने । ४४०५ स्वान्तं मनोभिधाने । ४४०६ ध्वान्तं तमोभिधाने ॥

२ । २० दृढः स्थूलबलयोः ३०६० ॥ ४४०७ दृढनिपातनं नकारहकारलोपार्थं परस्य च ढत्वार्थम् । ४४०८ अनिड्वचने हि रभावाप्रसिद्धिरलघुत्वात् । ४४०९ नलोपवचनं च ॥

२ । २१ प्रभौ परिवृढः ३०६१ ॥ ४४१० परिवृढनिपातनं च ॥

२ । २६ णेरध्ययने वृत्तम् ३०६६ ॥ ४४११ वृत्तनिपातने णिग्रहणमण्यन्तस्यावधारणप्रतिषेधार्थम् । ४४१२ निपातनं णिलोपे कुणप्रतिषेधार्थम् ॥

२ । २७ वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ३०६८ ॥ ४४१३ दान्तशान्तयोरुपधादीर्घत्वं च । ४४१४ स्पष्टच्छन्नयोरुपधाह्रस्वत्वं च ॥

२ । २८ रुष्यमत्वरसंघुषास्वनाम् ३०६९ ॥ ४४१५ घुषिरवनोर्वावचनमिट्प्रतिषेधाद्विप्रतिषेधेन ॥

२ । २९ हृषेर्लोमसु ३०७० ॥ ४४१६ हृषेर्लोमकेशकर्तृकस्येति वक्तव्यम् । ४४१७ विस्मितप्रतीघातयोरिति वक्तव्यम् ॥

२ । ३० अपचितश्च ३०७१ ॥ ४४१८ क्तिनि नित्यमिति वक्तव्यम् ॥

२ । ३६ स्नुक्रमोरनात्मनेपदनिमित्ते २३२३ ॥ ४४१९ स्नुक्रमोरनात्मनेपदनिमित्ते चेत्कृत्युपसंख्यानम् । ४४२० आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः ४४२१ सिद्धं तु स्नोरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् । ४४२२ क्रमेश्च । ४४२३ कर्तरि चात्मनेपदविषयात्कृति ॥

२ । ३७ ग्रहोऽलिटि दीर्घः २९६२ ॥ ४४२४ ग्रहेर्दीर्घत्व इड्ग्रहणम् । ४४२५ अग्रहणे ह्यसंप्रत्ययः षष्ठ्यभावात् । ४४२६ चिण्वदिटः प्रतिषेधः । ४४२७ यङ्लोपे च । ४४२८ इड्दीर्घ इति चेद्विप्रतिषिद्धम् । ४४२९ प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वाभावः ॥

२ । ४४ स्वरतिसूतिसूयतिधूञूदितो वा २२७१ ॥ ४४३० पुनर्वावचनं लिङ्सिचोर्निवृत्त्यर्थम् । ४४३१ स्वरतिरुदात्तः । ४४३२ वावचनं निवृत्त्यर्थम् । ४४३३ अनुदात्ते हि क्रिति वाप्रसङ्गः प्रतिषिध्य पुनर्विधानात् ॥

२ । ४७ इण्निष्ठायाम् ३०४९ ॥ ४४३४ इड्ग्रहणं नित्यार्थम् ॥

२ । ४८ तीषसहलुभरुषरिषः २३४० ॥ ४४३५ इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः ॥

२ । ५२ वसतिक्षुधोरिट् ३०४६ ॥ ४४३६ पुनरिड्ग्रहणं नित्यार्थम् ॥

२ । ५८ गमेरिट्परस्मैपदेषु २४०१ ॥ ४४३७ गमेरिट्परस्मैपदेषु चेत्कृत्युपसंख्यानम्
४४३८ सिद्धं तु गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् ॥

२ । ५९ न वृद्भ्यश्चतुर्भ्यः २३४८ ॥ ४४३९ वृतादिप्रतिषेधे च कृत्युपसंख्यानम् । ४४४० आत्मनेपदपर इड्वचने तत्परपरसीयुडेकादेशेष्विड्वचनम् । ४४४१ सिद्धं तु वृतादीनामात्मनेपदेन समानपदस्थस्येड्वचनात् । ४४४२ चतुस्तासिक्लृपिग्रहणानर्थक्यं च । ४४४३ निवृत्तत्वात्सकारस्य ॥

२ । ६२ उपदेशेऽत्वतः २२९९ ॥ ४४४४ तासावत्त्वप्रतिषेधे घसेः प्रतिषेधप्रसङ्गोऽकारवत्त्वात् । ४४४५ सिद्धं तु हलादिग्रहणात् । ४४४६ तस्य चाभावात्तासौ ॥

२ । ६३ ऋतो भारद्वाजस्य २२९६ ॥ ४४४७ ऋतो भारद्वाजस्येति नियमानुपपत्तिरप्राप्तत्वात्प्रतिषेधस्य । ४४४८ तत्र पचादिभ्य इड्वचनम् । ४४४९ योगविभागात्सिद्धम् ॥

२ । ६७ वस्वेकाजाद्घसाम् ३०९६ ॥ ४४५० वस्वेकाजाद्घसांवचनं नियमार्थम् । ४४५१ घासिग्रहणमनच्कत्वात् ॥

२ । ६८ विभाषा गमहनविदविशाम् ३०९९ ॥ ४४५२ दृशेश्चेति वक्तव्यम् ॥

२ । ७० ऋद्धनोः स्ये २३६६ ॥ ४४५३ स्वरतेर्वेट्त्वादृतः स्ये विप्रतिषेधेन ॥

२ । ८२ आने मुक् ३१०१ ॥ ४४५४ मुकि स्वरे दोषः । ४४५५ अभक्ते च । ४४५६ परादौ दीर्घप्रसङ्गः ॥

२ । ८४ अष्टन आ विभक्तौ ३७१ ॥ ४४५७ अष्टन्जनादिपथिमथ्यात्त्वेष्वान्तरतम्यादनुनासिकप्रसङ्गः । ४४५८ सिद्धमनण्त्वात् । ४४५९ उच्चारणसामर्थ्याद्वा ॥

२ । ९८ प्रत्ययोत्तरपदयोश्च १३७३ ॥ ४४६० त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहणं शब्दविशेषणत्वात् ॥

२ । ९९ त्रिचतुरोः स्त्रियां तिसृचतसृ २९८ ॥ ४४६१ तिस्रभावे संज्ञायां कन्युपसंख्यानम् । ४४६२ चतसर्याद्युदात्तनिपातनं च । ४४६३ उपदेशिवद्वचनं च । ४४६४ स्वरसिद्ध्यर्थम् ॥

२ । १०० अचि र ऋतः २९९ ॥ ४४६५ अचि रादेशे जस्युपसंख्यानं गुणपरत्वात् । ४४६६ न वानवकाशत्वाद्रस्य ॥

२ । १०१ जराया जरसन्यतरस्याम् २२७ ॥ ४४६७ नुमोऽनङ्जरसौ विप्रतिषेधेन ॥

२ । १०२ त्यदादीनामः २६९ ॥ ४४६८ त्यदादीनां द्विपर्यन्तानामकारवचनम् । ४४६९ त्यदादीनामकारेण सिद्धत्वाद्युष्मदस्मदोः शेषे लोपस्य लोपेन ज्ञायते प्राक्ततोऽदिति ॥ ४४७० अपि वोपसमस्तार्थमत्वाभावात्कृतं भवेत् । ४४७१ टिलोपष्टाबभावार्थः कर्तव्य इति तत्स्मृतम् ॥ ४४७२ अथवा शेषसप्तम्या शेषेलोपो विधीयते । ४४७३ लुप्तशिष्टे हि तस्याहुः कार्यसिद्धिं मनीषिणः ॥

२ । १०७ अदस औ सुलोपश्च ४३७ ॥ ४४७४ अदसः सौभेवेदौत्वं किं सुलोपो विधीयते । ४४७५ ह्रस्वाल्लुप्येत संबुद्धिः । ४४७६ न हलः । ४४७७ प्रकृतं हि तत् ॥ ४४७८ आप एत्त्वं भवेत्तस्मिन् । ४४७९ न झलीत्यनुवर्तनात् । ४४८० प्रत्ययस्थाच्च कादित्त्वम् । ४४८१ शीभावश्च प्रसज्यते ॥ ४४८२ सावौत्त्वप्रतिषेधः साकच्काद्वा सादुत्त्वं च । ४४८३ उत्तरपदभूतानामादेश उपदेशिवद्वचनम् । ४४८४ अनादिष्टार्थम् । ४४८५ बहिरङ्गलक्षणत्वात् ॥

२ । ११४ मृजेर्वृद्धिः २४७३ ॥ ४४८६ मृजेर्वृद्धिविधौ क्ङिप्रतिषेधः । ४४८७ धातोः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात्सिद्धम् । ४४८८ प्रयोजनं सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम् ॥

२ । ११५ अचो ञ्णिति २५४ ॥ ४४८९ वृद्धावब्ग्रहणं गोर्थम् । ४४९० योगविभागः सखिव्यञ्जनाद्यर्थः ॥

२ । ११७ तद्धितेष्वचामादेः १०७९ ॥ ४४९१ तद्धितेष्वचामादिवृद्धान्त्योपधालक्षणप्रतिषेधः । ४४९२ लोकविज्ञानाद्वा सिद्धम् । ४४९३ पुष्करसद्ग्रहणाद्वा ॥

३ । १ देविकाशिंशपादित्यवाड्दीर्घसत्त्रश्रेयसामात् १४३९ ॥ ४४९४ देविकादिषु तदादिग्रहणम् । ४४९५ अन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वा । ४४९६ आद्यज्विशेषणत्वाद्वा सिद्धम् । ४४९७ आन्तरतम्यनिवर्तकत्वाद्वा । ४४९८ न्यग्रोधे च केवलग्रहणात् । ४४९९ वहीनरस्येद्वचनम् ॥

३ । ३ न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् १०९८ ॥ ४५०० य्वाभ्यां परस्यावृद्धित्वम् । ४५०१ अपवादौ वृद्धेर्हि तौ । ४५०२ नित्यावैचौ तयोर्वृद्धिः । ४५०३ किमर्थं नेति शिष्यते ॥ ४५०४ ऐचोर्विषयार्थं प्रतिषेधसंनियोगवचनम् । ४५०५ यत्र य्वाभ्यां परा वृद्धिस्तत्राध्यर्धैर्यथा न तौ । ४५०६ अचामादेर्य्वाभ्यां हि तौ । ४५०७ कथं द्व्याशीतिके न तौ ॥ ४५०८ यत्र वृद्धिरचामादेस्तत्रैचावत्र य्वोर्हि सा । ४५०९ अथ कस्मात्पदान्ताभ्याम् । ४५१० यथेणो न भवेद्यणः ॥

३ । ८ श्वादेरिञि १९६० ॥ ४५११ प्रतिषेधे श्वादिग्रहणं ज्ञापकमन्यत्र श्वन्ग्रहणे तदादिग्रहणस्य शौवहान्यर्थम् । ४५१२ इकारादिग्रहणं च श्वागणिकाद्यर्थम् । ४५१३ तदन्तस्य चान्यत्र प्रतिषेधः ॥

३ । १० उत्तरपदस्य १३९६ ॥ ४५१४ तद्धितेष्वचामादिवृद्धेरुत्तरपदवृद्धिर्विप्रतिषेधेन द्व्याशीतिकाद्यर्थम् ॥

३ । १५ संख्यायाः संवत्सरसंख्यस्य च १७५२ ॥ ४५१५ संवत्सरग्रहणमनर्थकं परिमाणान्तस्येति कृतत्वात् । ४५१६ ज्ञापकं तु कालपरिमाणानां वृद्धिप्रतिषेधस्य (परिमाणग्रहणस्य) ॥

३ । ३२ हनस्तोऽचिण्णलोः २५७४ ॥ ४५१७ हन्तेस्तकारे तद्धिते प्रतिषेधः ॥

३ । ३४ नोदात्तोपदेशस्य मान्तस्यानाचमेः २७६३ ॥ ४५१८ अवमिकमिचमीनामिति वक्तव्यम् ॥

३ । ३७ शाच्छासाह्वाव्यावेपां युक् २५८५ ॥ ४५१९ णिच्प्रकरणे धूञ्प्रीञोर्नुग्वचनम् । ४५२० पातेर्लुग्वचनम् ॥

३ । ४४ प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ४६३ ॥ ४५२१ इत्त्वे कग्रहणं संघातग्रहणं चेदेतिकास्वप्राप्तिः । ४५२२ वर्णग्रहणं चेद्व्यवहितत्वादप्रसिद्धिः । ४५२३ वचनप्रामाण्यादिति चेद्रथकट्यादिष्वतिप्रसङ्गः । ४५२४ मामकनरकयोरुपसंख्यानं प्रत्ययस्थत्वात् । ४५२५ त्यक्त्यपोश्च प्रतिषिद्धत्वात् ॥

३ । ४५ न यासयोः ४६४ ॥ ४५२६ प्रतिषेधे त्यकन उपसंख्यानम् । ४५२७ पावकादीनां छन्दस्युपसंख्यानम् । ४५२८ आशिषि च । ४५२९ उत्तरपदलोपे च । ४५३० क्षिपकादीनां च । ४५३१ तारका ज्योतिषि । ४५३२ वर्णका तान्तवे । ४५३३ वर्तका शकुनौ प्राचाम् । ४५३४ अष्टका पितृदैवत्ये । ४५३५ वा सूतकापुत्रकावृन्दारकाणाम् ॥

३ । ४६ उदीचामातः स्थाने यकपूर्वायाः ४६५॥ ४५३६ यकपूर्वत्वे धात्वन्तप्रतिषेधः॥

३ । ४७ भस्त्रैषाजाज्ञाद्वास्वनञ्पूर्वाणामपि ४६६ ॥ ४५३७ भस्त्राग्रहणमुपसर्जनार्थम् । ४५३८ नञ्पूर्वग्रहणानर्थक्यं चोत्तरपदमात्रस्येद्वचनात् ॥

३ । ५० ठस्येकः ११७० ॥ ४५३९ ठादेशे वर्णग्रहणं चेद्धात्वन्तस्य प्रतिषेधः । ४५४० संघातग्रहणं चेदुणादिमाथितिकादीनां प्रतिषेधः । ४५४१ तस्माद्विशिष्टग्रहणम् ॥

३ । ५४ हो हन्तेर्ञ्णिन्नेषु ३५८ ॥ ४५४२ हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः । ४५४३ हकारस्येति चेड्ड्णित्यप्राप्तिः । ४५४४ स्थानिवद्भावाच्चाचो नकारेऽप्रसिद्धिः । ४५४५ वचनप्रामाण्यादिति चेदल्लोपे प्रतिषेधः । ४५४६ सिद्धं तूपधालोप इति वचनात् ॥

३ । ५५ अभ्यासाच्च २४३० ॥ ४५४७ अभ्यासात्कुत्वमसुपः ॥

३ । ५६ हेरचङि २५३१ ॥ ४५४८ हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वात् । ४५४९ ज्ञापकं त्वन्यत्र ण्यधिकस्य कुत्वविज्ञानार्थम् ॥

३ । ५७ सन्लिटोर्जेः २३३१ ॥ ४५५० जिग्रहणे ज्यः प्रतिषेधः ॥

३ । ५९ न क्वादेः २८७९ ॥ ४५५१ क्वायजित्रजियाचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्ववचनात् । ४५५२ शुच्युब्ज्योर्घञि कुत्वम् । ४५५३ अर्चेः कविधानात्सिद्धम् ॥

३ । ६१ भुजन्युब्जौ पाण्युपतापयोः २८७७ ॥ ४५५४ भुजः पाणौ । ४५५५ न्युब्जेः कर्तृत्वादप्रतिषेधः ॥

३ । ६६ यजयाचरुचप्रवचर्चश्च २८८२ ॥ ४५५६ प्रवचिग्रहणमनर्थकं वचोऽशब्दसंज्ञाभावात् । ४५५७ उपसर्गपूर्वनियमार्थमिति चेदविवावयस्य विशेषवचनात्सिद्धम् । ४५५८ ण्यप्रतिषेधे त्यजेरुपसंख्यानम् ॥

३ । ६९ भोज्यं भक्ष्ये २८८५ ॥ ४५५९ भोज्यमभ्यवहार्ये ॥

३ । ७१ ओतः श्यनि २५१० ॥ ४५६० ओतः शिति । ४५६१ उत्तरत्र शिद्ग्रहणाभावाय॥

३ । ७५ ष्ठिवुक्लमुचमां शिति २३२० ॥ ४५६२ दीर्घत्वमाङि चमः ॥

३ । ७७ इषुगमियमां छः २४०० ॥ ४५६३ इषेश्छत्वमहलि ॥

३ । ७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः २३६० ॥ ४५६४ पिबेर्गुणप्रतिषेधः ॥

३ । ८३ जुसि च २४८१ ॥ ४५६५ जुसि गुणे यासुट्प्रतिषेधः ॥

३ । ८५ जाग्रोऽविचिण्णल्ङित्सु २४८० ॥ ४५६६ चिण्णलोः प्रतिषेधसामर्थ्यादन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः । ४५६७ प्रसज्यप्रतिषेधे जुसि गुणप्रतिषेधप्रसङ्गः । ४५६८ उत्तमे च णलि । ४५६९ न वानन्तरस्य प्रतिषेधात् । ४५७० जुसि पूर्वेण गुणविधानम् । ४५७१ णलि च । ४५७२ अतोऽन्यत्र विधाने वावर्गुणत्वम् । ४५७३ न वा पर्युदाससामर्थ्यात् । ४५७४ वस्वर्थमिति चेन्न सार्वधातुकत्वात्सिद्धम् ॥

३ । ८६ पुगन्तलघूपधस्य च २१८९ ॥ ४५७५ संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति । ४५७६ विध्यपेक्षं लघोश्चासौ । ४५७७ कथं कुण्डिर्न दुष्यति ॥ ४५७८ धातोर्नुमः । ४५७९ कथं रञ्जेः । ४५८० स्यन्दिश्रन्थ्योर्निपातनात् । ४५८१ अनङ्गोपशिदीर्घत्वे विध्य-

वेदे न सिध्यतः ॥ ४५८२ अभ्यस्तस्य यदाहाचि । ४५८३ लङर्थं तत्कृतं भवेत् । ४५८४ ह्रुसनोर्यत्कृतं किन्त्वं ज्ञापकं स्याल्लघोर्गुणे ॥

३ । ८७ नाभ्यस्तस्याचि पिति सार्वधातुके २५०३ ॥ ४५८५ अभ्यस्तानामुपधाह्रस्वत्वमचि पस्पशाते चाकशीमि वावशतीरिति दर्शनात् । ४५८६ बहुलं छन्दस्यानुपग्जुजोपदिति दर्शनात् ॥

३ । ८८ भूसुवोस्तिङि २२२४ ॥ ४५८७ भूसुवोः प्रतिषेध एकाज्ग्रहणं बोभवीत्यर्थम् ॥

३ । ९२ तृणह इम् २५५५ ॥ ४५८८ तृणाहिग्रहणं अमिमोर्थ्यवस्थार्थम् । ४५८९ तृहिग्रहणे हीम्विषये अमभावोऽनवकाशत्वात् ॥

३ । ९९ तुरुस्तुशम्यमः सार्वधातुके २४४४ ॥ ४५९० पुनः सार्वधातुकग्रहणमपिदर्थम् ॥

३ । १०३ बहुवचने झल्येत् ३०९ ॥ ४५९१ अतो दीर्घाद्बहुवचन एत्त्वं विप्रतिषेधेन ॥

३ । १०७ अम्बार्थनद्योर्ह्रस्वः २६७ ॥ ४५९२ डलकवतीनां प्रतिषेधो वक्तव्यः । ४५९३ तल्ह्रस्वत्वं वा ङिसंबुद्ध्योः । ४५९४ अम्बार्थं द्व्यक्षरं यदि । ४५९५ मातॄणां मातच् पुत्रार्थमर्हते ॥

३ । १०९ जसि च २४१ । ४५९६ जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः । ४५९७ अम्बे दर्वि शतक्रत्वः पश्वे नृभ्यः किकिदीव्या ॥

३ । १११ घेर्ङिति २४५ ॥ ४५९८ घेर्ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः । ४५९९ सुबधिकारात्सिद्धम् ॥

३ । ११३ याडापः २९० ॥ ४६०० याड्विधानेऽतिखट्वायेत्यप्रतिषेधो ह्रस्वादेशत्वात् ॥

३ । ११६ ङेराम्नद्याम्नीभ्यः २७० ॥ ४६०१ इदुद्भ्यामाम्विधानमौत्त्वस्य परत्वात् । ४६०२ योगविभागात्सिद्धम् । ४६०३ औत्त्वे योगविभागः । ४६०४ सखिपतिभ्यामौत्त्वार्थः । ४६०५ एकयोगे ह्यप्रातिरत्वसंनियोगात् । ४६०६ न वाकारस्यान्वाचयवचनाद्यथा क्यङि सलोपः । ४६०७ अत्त्वे टाप्प्रतिषेधः । ४६०८ न वा संनिपातलक्षणस्यानिमित्तत्वात् । ४६०९ ङित्करणाद्वा ॥

४ । १ णौ चङ्युपधाया ह्रस्वः २३१४ ॥ ४६१० णौ चङ्युपधाया ग्रहणमन्त्यप्रतिषेधार्थम् । ४६११ उपधाह्रस्वत्वे णेर्णिच्युपसंख्यानम् ॥

४ । २ नाग्लोपिशास्वृदिताम् २५७२ ॥ ४६१२ अग्लोपिप्रतिषेधानर्थक्यं च स्थानिवद्भावात् ॥

४ । ३ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् २५६५ ॥ ४६१३ काण्यादीनां चेति वक्तव्यम् ॥

४ । ९ दयतेर्दिगि लिटि २३८८ ॥ ४६१४ दिग्यादेशस्य परत्वात्साभ्यासस्यादेशवचनम् ॥

४ । १० ऋतश्च संयोगादेर्गुणः २३७९ ॥ ४६१५ संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञर्थम् । ४६१६ ऋतो लिटि गुणाङ्डिणाति वृद्धिर्विप्रतिषेधेन । ४६१७ पुनः प्रसङ्गविज्ञानाद्वा सिद्धम् ॥

४ । १२ शॄदॄप्रां ह्रस्वो वा २४९५ ॥ ४६१८ ऋतो ह्रस्वत्वमित्त्वप्रतिषेधार्थम् ॥

४ । १३ केऽणः ८३४ ॥ ४६१९ केऽणो ह्रस्वत्वे तद्धितग्रहणं कृन्निवृत्त्यर्थम् ॥

४ । २४ एतेर्लिङि २४५७ ॥ ४६२० एतेर्लिङ्युपसर्गात् ॥

४ । ३० यङि च २६३३ ॥ ४६२१ यङ्प्रकरणे हन्तेर्हिंसायामीट् (घ्नी) ॥

४ । ३५ न च्छन्दस्यपुत्रस्य ३५५८ ॥ ४६२२ अपुत्रादीनामिति वक्तव्यम् । ४६२३ छन्दसि प्रतिषेधे दीर्घप्रतिषेधः । ४६२४ न वाध्याघस्याद्वचनमवधारणार्थम् ॥

४ । ४१ शाच्छोरन्यतरस्याम् ३०७५ ॥ ४६२५ श्यतेरित्त्वं व्रते नित्यम् ॥

४ । ४६ दो दद्घोः ३०७७ ॥ ४६२६ तान्ते दोषो दीर्घत्वं स्यात् । ४६२७ दान्ते दोषो निष्ठानत्वम् । ४६२८ धान्ते दोषो धत्वप्राप्तिः । ४६२९ थान्तेऽदोषस्तस्मात्थान्तः ॥

४ । ४७ अच उपसर्गात्तः ३०७८ ॥ ४६३० अच उपसर्गात्तत्वे आकारग्रहणम् । ४६३१ ओर्दीर्हि परस्य । ४६३२ अवर्णप्रकरणात्सिद्धम् । ४६३३ यतेरित्त्वादचस्तः ॥

४ । ४८ अपो भि ४४२ ॥ अपो भि मासश्छन्दसि । ४६३४ स्ववस्स्वतवसोर्मास उषसश्च त इष्यते ॥

४ । ५४ सनि मीमाघुरभलभशकपतपदामच इस् २६२३ ॥ ४६३५ इस्त्वं सनि राधो हिंसायाम् ॥

४ । ५५ आप्ज्ञप्यृधामीत् २६१९ ॥ ४६३६ ज्ञपेरीत्त्वमनन्त्यस्य ॥

४ । ५८ अत्र लोपोऽभ्यासस्य २६२० ॥ ४६३७ अभ्यासस्यानचि ॥

४ । ६० हलादिः शेषः २१७९ ॥ ४६३८ हलादिशेष षष्ठीसमास इति चेदजादिषु शेषप्रसङ्गः । ४६३९ कर्मधारय इति चेदादिशेषनिमित्तत्वाल्लोपस्य तदभावे लोपवचनम् । ४६४० तस्मादनादिलोपः ॥

४ । ६१ शर्पूर्वाः खयः २२५९ ॥ ४६४१ शर्पूर्वशेषे खपूर्वग्रहणम् । ४६४२ आदिशेषप्रसङ्गस्तु । ४६४३ शर्पूर्ववचनं किमर्थमिति चेत्खयां लोपप्रतिषेधार्थम् । ४६४४ व्यपकर्षविज्ञानात्सिद्धम् ॥

४ । ६७ द्युतिस्वाप्योः संप्रसारणम् २३४४ ॥ ४६४५ स्वापिग्रहणं व्यपेतार्थम् । ४६४६ तत्र क्यजन्तेऽतिप्रसङ्गः । ४६४७ सिद्धं तु णिज्ग्रहणात् ॥

४ । ७५ निजां त्रयाणां गुणः श्लौ २५०२ ॥ ४६४८ त्रिग्रहणानर्थक्यं तु गणान्तत्वात् । ४६४९ उत्तरार्थं तु ॥

४ । ८२ गुणो यङ्लुकोः २६३०॥४६५० ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वादि परं दीर्घत्वम् । ४६५१ न वाभ्यासविकारेष्वपवादस्योत्सर्गाबाधकत्वात् । ४६५२ प्रयोजनं सन्वद्भावस्य दीर्घत्वम् । ४६५३ मान्प्रभृतीनां दीर्घत्वमित्त्वस्य । ४६५४ गणेरीत्वं हलादिशेषस्य ॥

४ । ८३ दीर्घोऽकितः २६३२ ॥ ४६५५ अकिद्वचनमन्यत्र किदन्तस्यालोऽन्त्यनिवृत्त्यर्थम् । ४६५६ प्रयोजनं ह्रस्वत्वात्त्वेत्त्वगुणेषु । ४६५७ विप्रतिषेधात्सिद्धम् । ४६५८ तदन्तग्रहणाद्वा ॥

४ । ८५ नुगतोऽनुनासिकान्तस्य २६४३ ॥ ४६५९ नुकि यंयस्यते रंरम्यत इति रूपासिद्धिः । ४६६० अनुस्वारागमवचनात्सिद्धम् । ४६६१ पदान्तवच्च ॥

४ । ९० रीगृदुपधस्य च २६४४ ॥ ४६६२ रीगृत्वतः संयोगार्थम् ॥

४।९१ रुग्रिकौ च लुकि २६९२॥ ४६६३ मर्मृज्यते मर्मृज्यमानास इति चोपसंख्यानम्॥

४।९३ सन्वल्लघुनि चङ्परेऽनग्लोपे २३१६॥ ४६६४ सन्वद्भावदीर्घत्वे णेर्णिच्युपसंख्यानम्। ४६६५ मीमादीनां तु लोपप्रसङ्गः। ४६६६ सिद्धं तु रूपातिदेशात्। ४६६७ अङ्गान्यत्वाद्वा सिद्धम्॥

इति सप्तमोऽध्यायः।

अष्टमोऽध्यायः।

१।१ सर्वस्य द्वे २१३९॥ ४६६८ सर्वग्रहणमलोऽन्त्यनिवृत्त्यर्थम्। ४६६९ षष्ठीनिर्देशार्थं च। ४६७० अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः। ४६७१ न वा पदाधिकारात्। ४६७२ तच्च समासतद्धितवाक्यनिवृत्त्यर्थम्। ४६७३ सगतिग्रहणं च॥

१।४ नित्यवीप्सयोः २१४०॥ ४६७४ अनवयवाभिधानं वीप्सार्थ इति चेज्जात्याख्यायां द्विर्वचनप्रसङ्गः। ४६७५ न वैकार्थत्वाज्जातेः। ४६७६ अनेकार्थाश्रयत्वाच्च वीप्सायाः। ४६७७ निवर्त्तकत्वाद्वा। ४६७८ सर्वपदसगतिग्रहणानर्थक्यं चार्थाभिधाने द्विर्वचनविधानात्। ४६७९ वीप्सायां सर्वाभिधाने वचनाप्रसिद्धिः। ४६८० एकाभिधानेऽसर्वद्रव्यगतिः। ४६८१ न वा पदार्थत्वात्॥

१।५ परेर्वर्जने २१४१॥ ४६८२ परेरसमासे। ४६८३ परेर्वर्जने वावचनम्॥

१।८ वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु २१४३॥ ४६८४ असूयाकुत्सनयोः कोपभर्त्सनयोश्चैकार्थत्वात्पृथक्त्वनिर्देशानर्थक्यम्॥

१।९ एकं बहुव्रीहिवत् २१४४॥ ४६८५ एकस्य द्विर्वचनसंबन्धेनेति चेदर्थनिर्देशः। ४६८६ न वा वीप्साधिकारात्। ४६८७ बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ। ४६८८ सर्वनामस्वरसमासान्तेषु दोषः॥

१।११ कर्मधारयवदुत्तरेषु २१४६॥ ४६८९ कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि॥

१।१२ प्रकारे गुणवचनस्य २१४७॥ ४६९० प्रकारे सर्वेषां गुणवचनत्वात्सर्वप्रसङ्गः। ४६९१ सिद्धं तु प्रकृत्यर्थविशेषणत्वात्। ४६९२ आनुपूर्व्ये। ४६९३ स्वार्थेऽवधार्यमाणेऽनेकस्मिन्। ४६९४ चापले। ४६९५ क्रियासमभिव्याहारे। ४६९६ आभीक्ष्ण्ये। ४६९७ डाचि च। ४६९८ पूर्वप्रथमयोरर्थातिशयविवक्षायाम्। ४६९९ डतरडतमयोः समसंप्रधारणायां स्त्रीनिगदे भावे। ४७०० कर्मव्यतिहारे सर्वनाम्नः समासवच्च बहुलं यदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्य। ४७०१ स्त्रीनपुंसकयोरुत्तरपदस्य वाम्भावः॥

१।१५ द्वंद्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु २१५०॥ ४७०२ अत्यन्तसहचरिते लोकविज्ञाते द्वंद्वमित्युपसंख्यानम्। ४७०३ द्वंद्वमिति पूर्वपदस्य चाम्भाव उत्तरपदस्य चात्वं नपुंसकत्वं च॥

१।१६-१७ पदस्य ४०१। पदात् ४०२॥ ४७०४ पदाधिकारः प्रागपदान्ताधिकारात्। ४७०५ पदात्प्राक्सुपि कुत्सनात्। ४७०६ यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्। ४७०७ इह

वचने ह्यपदान्तस्याप्राप्तिः । ४७०८ न वा पदाधिकारस्य विशेषणत्वात् । ४७०९ अन्तग्रहणाद्वा नलोपे ॥

१ । १८ अनुदात्तं सर्वमपादादौ ४०३ ॥ ४७१० सर्ववचनमनादेरनुदात्तार्थम् । ४७११ सर्ववचनमनादेरनुदात्तार्थमिति चेल्लुटि प्रतिषेधात्सिद्धम् । ४७१२ अलोऽन्त्यविधिप्रसङ्गस्तु । ४७१३ ल्लटि प्रतिषेधात्सिद्धम् । ४७१४ समानवाक्ये निघातयुष्मदस्मदादेशाः । ४७१५ पदयार्थैश्च प्रतिषेधः ॥

१ । २६ सपूर्वायाः प्रथमाया विभाषा ४१० ॥ ४७१६ युष्मदस्मदोरन्यतरस्यामनन्वादेशे । ४७१७ सर्व एव वांनावादयोऽनन्वादेशे विभाषा वक्तव्याः ।

१ । २७ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ३९३४ ॥ ४७१८ तिङो गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । ४७१९ अनुदात्तविशेषणे ह्यन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् । ४७२० अनुदात्तग्रहणं वा ॥

१ । २८ तिङ्ङतिङः ३९३५ ॥ ४७२१ अतिङ्ग्रहणमनर्थकं समानवाक्याधिकारात् ॥

१ । ३० निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ३९३७ ॥ ४७२२ चाण्णेद्विशिष्टश्चेदर्थे ॥

१ । ५१ गत्यर्थलोटा ल्लण्न चेत्कारकं सर्वान्यत् ३९५८ ॥ ४७२३ ल्लटः प्रकृतिभावे कर्तुरन्यत्व उपसंख्यानं कारकान्यत्वात् । ४७२४ कर्तृसामान्यात्सिद्धमिति चेत्तद्देदेऽन्यसामान्ये प्रकृतिभावः । ४७२५ न चेत्कर्ता सर्वान्य इति चेदन्याभिधाने प्रतिषेधमेके । ४७२६ सिद्धं तु तिङोरेकद्रव्याभिधानात् ॥

१ । ५५ आम एकान्तरमामन्त्रितमनान्तिके ३९६२ ॥ ४७२७ आम एकान्तर ऐकश्रुत्यप्रतिषेधः । ४७२८ निघातप्रसङ्गस्तु । ४७२९ सिद्धं तु प्रतिषेधाधिकारे प्रतिषेधवचनात् ॥

१ । ५६ यद्धितुपरं छन्दसि ३९६३ ॥ ४७३० यद्धितुपरस्य छन्दस्यनिघातोऽन्यपरप्रतिषेधार्थः ॥

१ । ५७ चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ३९६४ ॥ ४७३१ आम्रेडितेष्वगतेः सगतिरपि तिङित्यत्र गतिग्रहण उपसर्गग्रहणम् । ४७३२ सर्वत्रैवाष्टमिके गतिग्रहण उपसर्गग्रहणम् ॥

१ । ६६ यद्वृत्तान्नित्यम् ३९७३ ॥ ४७३३ वा याथाकाम्ये ॥

१ । ६७ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ३९७४ ॥ ४७३४ पूजितस्यानुदात्तत्वे काष्ठादिग्रहणम् । ४७३५ मलोपवचनं च ॥

१ । ६८ । सगतिरपि तिङ् ३९७५ ॥ ४७३६ सगतिग्रहणमपदत्वात् । ४७३७ उत्तरार्थं च । ४७३८ तिङ्निघातात्पूजनात्पूजितमनुदात्तं विप्रतिषेधेन ॥

१ । ६९ कुत्सने च सुप्यगोत्रादौ ३९७६ ॥ ४७३९ सुपि कुत्सने क्रियायाः । ४७४० मकारलोपोऽतिङि । ४७४१ पूतिश्चानुबन्धः । ४७४२ विभाषितं चापि बह्वर्थम् ॥

१ । ७० गतिर्गतौ ३९७७ ॥ ४७४३ गतेरनुदात्तत्वे गतिग्रहणानर्थक्यं तिङ्यवधारणात् । ४७४४ छन्दोऽर्थमिति चेन्नागतित्वात् ॥

१ । ७१ तिङि चोदात्तवति ३९७८ ॥ ४७४५ तिङ्ग्रहणमुदात्तवतः प्रतिषेधार्थम् । ४७४६ यद्योगाद्गतिः । ४७४७ यद्योगाद्गतिरिति चेत्प्रत्ययोदात्तत्वेऽप्रसिद्धिः ॥

१ । ७२ आमन्त्रितं पूर्वमविद्यमानवत् ४१२ ॥ ४७४८ पूर्वं प्रति विद्यमानत्वादुत्तरत्रानन्तर्याप्रसिद्धिः । ४७४९ सिद्धं तु पदपूर्वस्येति वचनात् । ४७५० अविद्यमानवत्त्वे प्रयोजनमामन्त्रितयुष्मदस्मन्तिङ्निघाताः । ४७५१ पूजायामनन्तरप्रतिषेधः । ४७५२ जात्वपूर्वम् । ४७५३ आहो उताहो चानन्तरविधौ । ४७५४ आम एकान्तरविधौ ॥

२ । १ पूर्वत्रासिद्धम् १२ ॥ ४७५५ पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य । ४७५६ अपवादो वचनप्रामाण्यात् । ४७५७ पूर्वत्रासिद्धमधिकारः । ४७५८ परस्य परस्य पूर्वत्र पूर्वत्रासिद्धविज्ञानार्थः । ४७५९ अनधिकारे हि समुदायस्य समुदायेऽसिद्धविज्ञानम् । ४७६० तत्रायथेष्टप्रसङ्गः । ४७६१ तस्मादधिकारः ॥

२ । २ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ३५३ ॥ ४७६२ संज्ञाग्रहणानर्थक्यं च तन्निमित्तत्वाल्लोपस्य । ४७६३ स्वरेऽवधारणाच ॥

२ । ३ न मु ने ४३९ ॥ ४७६४ न मु टादेशे ॥

२ । ४ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ३६५७ ॥ ४७६५ यण्स्वरो यणादेशे स्वरितयणः स्वरितार्थम् । ४७६६ आश्रयात्सिद्धत्वमिति चेदुदात्तात्स्वरिते दोषः ॥

२ । ५ स्वरितो वानुदात्ते पदादौ ३६५९ ॥ ४७६७ एकादेशस्वरोऽन्तरङ्गः । ४७६८ अयवायावेकादेशशतृस्वरैकानुदात्तसर्वानुदात्तार्थम् । ४६७९ संयोगान्तलोपो रोरुत्वे हरिवो मेदिनीं त्वा । ४७७० प्लुतिश्च । ४७७१ सिज्लोप एकादेशे । ४७७२ संयोगादिलोपः संयोगान्तलोपे । ४७७३ निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु । ४७७४ वस्वादिषु दत्वं सौ दीर्घत्वे । ४७७५ अदस ईत्वोत्वे स्वरे बहिष्पदलक्षणे । ४७७६ प्रगृह्यसंज्ञायां च । ४७७७ प्लुतिस्तुग्विधौ छे । ४७७८ श्चुत्वं धुट्त्वे । ४६७९ अभ्यासजश्त्वचर्त्वमेत्त्वतुकोः । ४७८० द्विर्वचने परसवर्णत्वम् । ४७८१ पदाधिकारश्चेल्लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि ॥

२ । ७ नलोपः प्रातिपदिकान्तस्य २३६ ॥ ४७८२ नलोपेऽन्तग्रहणं पदाधिकारस्य विशेषणत्वात् । ४७८३ अह्नो नलोपप्रतिषेधः । ४७८४ अहन्ग्रहणादिति चेत्संबुद्ध्यर्थं वचनम् ॥

२ । ८ न ङिसंबुद्ध्योः ३५२ ॥ ४७८५ न ङिसंबुद्ध्योरनुत्तरपदे । ४७८६ वा नपुंसकानाम् । ४६८७ भत्वात्तु ङौ प्रतिषेधानर्थक्यम् ॥

२ । ९ मादुपधायाश्च मतोर्वोऽयवादिभ्यः १८९७ । ४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ३०१६ ॥ ४७८८ अनन्त्ययोरपि निष्ठामतुपोरादेशः । ४७८९ नामंते प्रतिषेधः ॥

२ । १६ अनो नुट् ३६०१ ॥ ४७९० अनो नुकि विनामरुविधिप्रतिषेधः । ४७९१ परादौ वत्वप्रतिषेधोऽवग्रहश्च । ४७९२ मत्वात्सिद्धम् । ४७९३ अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि । ४७९४ घग्रहणं च ॥

२ । १७ नाद्धस्य ३६०२ ॥ ४७९५ ईद्रथिनः । ४७९६ भूरिदान्नस्तुट् ॥

२ । १८ कृपो रो लः २३५० ॥ ४७९७ कृपणादीनां प्रतिषेधो वक्तव्यः । ४७९८ वालमूललघ्वलमङ्गुलीनां वा लो रमापद्यत इति वक्तव्यम् । ४७९९ संज्ञाछन्दसोर्वा कपिलकादीनामिति वक्तव्यम् ॥

२ । १९ उपसर्गस्यायतौ २३२६ ॥ ४८०० रेफस्यायताविति चेत्परेरुपसंख्यानम् । ४८०१ उपसर्गस्येति चेदेकादेशेऽप्रसिद्धिः ॥

२ । २१ अचि विभाषा २५४१ ॥ ४८०२ णावुपसंख्यानम् ॥

२ । २२ परेश्च घाङ्कयोः ३२६२ ॥ ४८०३ योगे च । ४८०४ सङि लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि । ४८०५ प्रयोजनं गिरौ गिरः पयो धावति द्विष्टराम् नृपत्स्थानं काष्ठशक्स्थाता कुञ्चा धुर्य इति ॥

२ । २३ संयोगान्तस्य लोपः ५४ ॥ ४८०६ संयोगान्तस्य लोपे यणः प्रतिषेधः । ४८०७ न वा झलो लोपात् । ४८०८ बहिरङ्गलक्षणत्वाद्वा । ४८०९ संयोगान्तलोपे सग्रहणम् । ४८१० रुविधानस्यानवकाशत्वात् । ४८११ योगविभागात्सिद्धम् ॥

२ । २५ धि च २२४९ ॥ ४८१२ धि सकारे सिचो लोपः । ४८१३ चकाद्धीति प्रयोजनम् । ४८१४ आशाध्वं तु कथं ते स्यात् । ४८१५ जश्त्वं सस्य भविष्यति ॥ ४८१६ सर्वत्रैवं प्रसिद्धं स्यात् । ४८१७ श्रुतिश्चापि न भिद्यते । ४८१८ लुङश्चापि न मूर्धन्ये ग्रहणम् । ४८१९ सोटि दुष्यति ॥ ४८२० घसिभस्योर्न सिध्येत्तु । ४८२१ तस्मात्सिज्ग्रहणं न तत् । ४८२२ छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे ॥

२ । ३२ दादेर्धातोर्घः ३२५ ॥ ४८२३ ह्मग्रहोर्भश्छन्दसि हस्य ॥

२ । ३८ दधस्तथोश्च २५०१ ॥ ४८२४ दधस्तथोरनुकर्षणानर्थक्यं स्थानिवत्प्रतिषेधात् । ४८२५ इतरथा ह्यलोपे प्रतिषेधः ॥

२ । ४२ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ३०१६ ॥ ४८२६ निष्ठादेशे पूर्वग्रहण परस्यादेशप्रतिषेधार्थम् । ४८२७ पञ्चमीनिर्दिष्टाद्धि परस्य । ४८२८ वृद्धिनिमित्ताद्धि प्रतिषेधः । ४८२९ प्रयोजनं कार्तिंकीतिफौल्लयः । ४८३० न वा बहिरङ्गलक्षणत्वात् ॥

२ । ४४ ल्वादिभ्यः ३०१८ ॥ ४८३१ ऋकारल्वादिभ्यः क्तिन्निष्ठावत् । ४८३२ दुग्वोर्दीर्घश्च । ४८३३ पूञो विनाशे । ४८३४ सिनोतेर्ग्रासकर्मकर्तृकस्य ॥

२ । ४८ अञ्चोऽनपादाने ३०२४ ॥ ४८३५ अञ्चेर्नत्वे व्यक्तप्रतिषेधः । ४८३६ अञ्जिविज्ञानात्सिद्धम् । ४८३७ अञ्चत्यर्थ इति चेदञ्जेस्तदर्थत्वात्सिद्धम् ॥

२ । ५० निर्वाणोऽवाते ३०२९ ॥ ४८३८ अवाताभिधाने ॥

२ । ५५ अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ३०३५ ॥ ४८३९ कृशेः क एष विहित इगुपधात् । ४८४० स्वरे हि दोषो भवति परिकृशे । ४८४१ पदस्य लोपो विहित इति मतं जगत्यनन्ना भवति हि रुचिरा । ४८४२ फलेर्लत्व उत्पूर्वस्योपसंख्यानम् । ४८४३ उत्फुल्लसंफुल्लयोरिति वक्तव्यम् ॥

२ । ५८ वित्तो भोगप्रत्यययोः ३०४१ ॥ ४८४४ यस्य विदेः अशक्तौ तत्परत्वे तनवचने तदु वा प्रतिषेधौ । ४८४५ श्यन्विकरणान्नविधिश्छिदितुल्यः । ४८४६ लुग्विकरणो वलिपर्यवपन्नः ॥

२ । ६८ अहन् ४४३ ॥ ४८४७ रुविधावह्नो रूपरात्रिरथंतरेषूपसंख्यानम् ॥

२ । ६९ रोऽसुपि १७२ ॥ ४८४८ अमुपि रादेशे उपसर्जनसमासे प्रतिषेधोऽलुकि । ४८४९ सिद्धं तु सुपि प्रतिषेधात् ॥

२।७० भस्नरूधरवरित्युभयथा छन्दसि ३६०४ ॥ ४८५० छन्दसि भाषायां च प्रचे-
तसो राजन्युपसंख्यानम्। ४८५१ अहरादीनां पत्यादिषूपसंख्यानम्॥
२।७२ वसुस्रंसुध्वंस्वनडुहां दः ३३४ ॥ ४८५२ अनडुहो दत्वे नकारप्रतिषेधः।
४८५३ सिद्धं तु प्रतिपदविधानान्नुमः॥
२।७८ उपधायां च २२६५ ॥ ४८५४ उपधादीर्घत्वेऽभ्यासजिन्विचतुर्णां प्रतिषेधः।
४८५५ उणादिप्रतिषेधश्च ॥
२।८० अदसोऽसेर्दादु दो मः ४१९ ॥ ४८५६ अदसोऽनोस्त्रेः। ४८५७ तत्र पदाधिका-
रादपदान्तस्याप्राप्तिः। ४८५८ सिद्धं तु सकारप्रतिषेधात्। ४८५९ दाद्ग्रहणमनन्त्यप्रतिषे-
धार्थम्॥
२।८१ एत ईद्बहुवचने ४३८ ॥ ४८६० ईत्वं बहुवचनान्तस्य ॥
२।८२ वाक्यस्य टेः प्लुत उदात्तः ९३ ॥ ४८६१ वाक्याधिकारः पदनिवृत्त्यर्थः।
४८६२ टिग्रहणमलोन्त्यनियमे व्यञ्जनान्तार्थम्। ४८६३ सर्वादेशप्रसङ्गस्तु ॥
२।८३ प्रत्यभिवादेऽशूद्रे ९४ ॥ ४८६४ अशूद्रस्त्र्यसूयकेषु। ४८६५ भोराजन्यविशां
वा। ४८६६ सर्वस्यैव नाम्नः प्रत्यभिवादे भोःशब्द आदेशो वक्तव्यः॥
२।८५ हैहेप्रयोगे हैहयोः ९६ ॥ ४८६७ हैहेप्रयोगे हैहेग्रहणं हैहयोः प्लुत्यर्थम्।
४८६८ प्रयोगग्रहणमर्थवद्ग्रहणेऽनर्थकार्थम्। ४८६९ पुनर्हैहेग्रहणमनन्त्यार्थम्॥
२।८६ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ९७ ॥ ४८७० गुरोः प्लुतविधाने
लघोरन्त्यस्य प्लुतप्रसङ्गोऽन्येन विहितत्वात्। ४८७१ न वानन्त्यस्यापि वचनमुभयनिर्दे-
शार्थम्। ४८७२ प्राग्वचनं विभाषार्थम्। ४८७३ प्राग्वचनानर्थक्यं चैकैकस्येति वचनात्॥
२।८८ ये यज्ञकर्मणि ३६०७ ॥ ४८७४ ये यज्ञकर्मणीत्यतिप्रसङ्गः। ४८७५ सिद्धं तु
ये यजामह इति ब्रूह्यादिषूपसंख्यानात्॥
२।८९ प्रणवष्टेः ३६०८ ॥ ४८७६ टिग्रहणं सर्वादेशार्थम्॥
२।९२ अग्नीत्प्रेषणे परस्य च ३६११ ॥ ४८७७ अग्नीत्प्रेषणे इत्यतिप्रसङ्गः। ४८७८
सिद्धं त्वोश्रावये परस्य चेतिवचनात्। ४८७९ ओश्रावयाश्रावययोरिति वक्तव्यम्। ४८८०
बहुलमन्यत्रेति वक्तव्यम्॥
२।९९ आम्रेडितं भर्त्सने ३६१४ ॥ ४८८१ भर्त्सने पर्यायेण ॥
२।१०३ स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु ३६२२ ॥ ४८८२ असूयादिषु
वावचनम्॥
२।१०६ प्लुतावैच इदुतौ ३६२५ ॥ ४८८३ ऐचोरुभयविवृद्धिप्रसङ्गादिदुतोः प्लुतव-
चनम्। ४८८४ तत्रायथेष्टप्रसङ्गः। ४८८५ सिद्धं त्विदुतोर्दीर्घवचनात्॥
२।१०७ एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ३६२६ ॥ ४८८६
प्लुतविकारे पदान्तग्रहणम्। ४८८७ विषयपरिगणनं च। ४८८८ प्रश्नान्ताभिपूजितविचार्यमा-
णप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्। ४८८९ आमन्त्रिते छन्दस्युपसंख्यानम्॥
३।१ मतुवसो रु संबुद्धौ छन्दसि ३६२८ ॥ ४८९० मतुवसो रादेशो वन उपसंख्या-
नम्। ४८९१ विभाषा भवद्भगवदघवतामोच्चावस्य ॥

३ । ५५ समः सुटि १३५ । ६ पुमः खय्यम्परे १३९ । १२ कानाम्रेडिते १४३ ॥ ४८९२ संपुंकानां सत्वम् । ४८९३ रुविधौ ह्यनिष्टप्रसङ्गः ॥

३ । १३ ढो ढे लोपः २३३५ ॥ ४८९४ ढलोपेऽपदान्तग्रहणम् । ४८९५ जश्भावादिति चेदुत्तरत्र ढस्याभावादपवादप्रसङ्गः । ४८९६ तस्मात्सिद्धवचनम् । ४८९७ संग्रहणं वा ॥

३ । १५ खरवसानयोर्विसर्जनीयः ७६ ॥ ४८९८ विसर्जनीयोऽनुत्तरपदे । ४८९९ न वा बहिरङ्गलक्षणत्वात् ॥

३ । १७ भोभगोअघोअपूर्वस्य योऽशि १६७ ॥ ४९०० अश्ग्रहणमनर्थकमन्यत्राभावात् ॥

३ । २० ओतो गार्ग्यस्य १६९ ॥ ४९०१ ओकाराल्लोपवचनं नित्यार्थम् ॥

३ । २६ हे मपरे वा १२७ ॥ ४९०२ यवलपरे यवला वा ॥

३ । २९-३०-३१ ङःसि धुट् १३१ । नश्च १३२ । शि तुक् १३३ । २८ ङ्णोः कुक् टुक् शरि १३० । ३२ ङमो ह्रस्वादचि ङमुण् नित्यम् १३४ ॥ ४९०३ धुगादिषु टुत्वणत्वप्रतिषेधः । ४९०४ परादौ छत्वषत्वविधिप्रतिषेधः ॥

३ । ३२ ङमो ह्रस्वादचि ङमुण् नित्यम् १३४ ॥ ४९०५ ङमुटि पदादिग्रहणम् ॥

३ । ३६ वा शरि १५१ ॥ ४९०६ वाशर्प्रकरणे खर्परे लोपः ॥

३ । ३७ कुप्वोः ≍क≍पौ च १४२ ॥ ४९०७ सस्य कुप्वोर्विसर्जनीयजिह्वामूलीयोपध्मानीयाः । ४९०८ विसर्जनीयादेशे हि शर्परयोरेवादेशप्रसङ्गः ॥

३ । ३८ सोऽपदादौ १५२ ॥ ४९०९ सोऽपदादावनव्ययस्य । ४९१० रोः काम्ये नियमार्थम् ॥

३ । ४१ इदुदुपधस्य चाप्रत्ययस्य १५५ ॥ ४९११ इदुदुपधस्य चाप्रत्ययस्येति चेत्पुम्मुहुसोः प्रतिषेधः । ४९१२ वृद्धिभूतानां षत्वं वक्तव्यम् । ४९१३ प्लुतानां तादौ च । ४९१४ न वा बहिरङ्गलक्षणत्वात् । ४९१५ भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तात्षत्वप्रतिषेधस्य ॥

३ । ४५ नित्यं समासेऽनुत्तरपदस्थस्य १५९ ॥ ४९१६ नानापदार्थयोर्वर्तमानयोः ख्यायते यदा योगः । ४९१७ तस्मिन्षत्वं कार्यं तद्युक्तं तच्च मे नेह ॥ ४९१८ ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वं न मे प्रसज्येत । ४९१९ तस्मादिह व्यपेक्षां सामर्थ्यं साधु मन्यन्ते ॥ ४९२० अथ चेत्कृदन्तमेतत्ततोऽधिके नैव मे भवेत्प्राप्तिः । ४९२१ वाक्ये च मे विभाषा प्रतिषेधो न प्रकल्प्येत ॥ ४९२२ अथ चेत्संविज्ञानं नित्ये षत्वे ततो विभाषेयम् । ४९२३ सिद्धं च समासे । ४९२४ प्रतिषेधार्थस्तु यत्नोऽयम् ॥

३ । ५६ सहेः साडः सः ३३५ ॥ ४९२५ साडः षत्वे समानशब्दप्रतिषेधः । ४९२६ अर्थवद्ग्रहणात्सिद्धम् । ४९२७ अर्थवद्ग्रहणात्सिद्धमिति चेत्तद्धितलोपेऽर्थवत्त्वात्प्रतिषेधः ॥

३ । ५८ नुम्विसर्जनीयशर्व्यवायेऽपि ४३४ ॥ ४९२८ नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेधः । ४९२९ योगविभागात्सिद्धम् ॥

३ । ५९ आदेशप्रत्यययोः २१२ ॥ ४९३० आदेशप्रत्यययोः षत्वे सरकः (सरगादीनाम्) प्रतिषेधः । ४९३१ बहुवचनात्सिद्धम् । ४९३२ आदेशप्रत्यययोरित्यवयवषष्ठी

नोर्द्विर्वचने प्रतिषेधः । ४९३३ समानाधिकरणानां चाप्राप्तिः । ४९३४ नानाविभक्तीनां समासानुपपत्तिः । ४९३५ योगविभागात्सिद्धम् ॥

३ । ६४ स्थादिष्वभ्यासेन चाभ्यासस्य २२७७ ॥ ४९३६ स्थादिष्वभ्यासवचनं नियमार्थम् । ४९३७ तद्व्यवाये चाशोपदेशार्थम् । ४९३८ अवर्णार्थं षाणि प्रतिषेधार्थं च ॥

३ । ६५ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् २२७० ॥ ४९३९ उपसर्गात्षत्वे निस उपसंख्यानम् । ४९४० न वा वर्णाश्रयत्वात्षत्वस्य तद्विशेषक उपसर्गो धातुश्च । ४९४१ सुनोत्यादीनां षत्वे ण्यन्तस्योपसंख्यानमाधिकत्वात् । ४९४२ न वावयवस्यानन्यत्वात् । ४९४३ नामधातोस्तु प्रतिषेधः । ४९४४ न वानुपसर्गत्वात् ॥

३ । ७८–७९ इणः षीध्वं लुङ्लिटां धोऽङ्गात् २२४७ । विभाषेटः २३२९ ॥ ४९४५ इण्ग्रहणं ढत्वे कवर्गनिवृत्त्यर्थम् । ४७४६ तत्र प्रत्ययपरत्वे इटो लिटि ढत्वं परादित्वात् । ४९४७ धकारपरत्वे षीध्वम्यनन्तरत्वादिटो विभाषाभावः । ४९४८ इण्ग्रहणस्य चाविशेषणत्वात्स्यादिमात्रे ढत्वप्रसङ्गः ।

३ । ८२ अग्नेः स्तुस्तोमसोमाः ९२४ ॥ ४९४९ अग्नेर्दीर्घात्सोमस्य । ४९५० इतरथा ह्यनिष्टप्रसङ्गः ॥

३ । ८५ मातुःपितुर्भ्यामन्यतरस्याम् ९८३ ॥ ४९५१ सान्ताभ्यां चेति वक्तव्यम् । ४९५२ मातुःपितुरिति सान्तग्रहणानर्थक्यमेकदेशविकृतस्यानन्यत्वात् ॥

३ । ८८ सुविनिर्दुर्भ्यःसुपिसूतिसमाः २४७७ ॥ ४९५३ सुपेः षत्वं स्वपेर्मा भूत् । ४९५४ विसुष्वापेति केन न । ४९५५ हलादिशेषान्न सुपिः । ४९५६ इष्टं पूर्वं प्रसारणम् । ४९५७ स्थादीनां नियमो नात्र प्राक्सितादुत्तरः सुपिः । ४९५८ अनर्थके विषुषुपुः । ४८५९ सुपिभूतो द्विरुच्यते ॥

३ । ९१ कपिष्ठलो गोत्रे ३०८४ ॥ ४९६० कपिष्ठलो गोत्रप्रकृतौ ॥

३ ९७ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः २९१८ ॥ ४९६१ स्थ स्थास्थिन्स्थॄणामिति वक्तव्यम् ॥

३ । १०१ ह्रस्वात्तादौ तद्धिते १३२९ ॥ ४९६२ ह्रस्वात्तादौ तिङि प्रतिषेधः ॥

३ । १०५ स्तुतस्तोमयोश्छन्दसि ३६४२ ॥ ४९६३ स्तुतस्तोमयोश्छन्दस्यनर्थकं वचनं पूर्वपदादिति सिद्धत्वात् ॥

३ । १०८ सनोतेरनः ३६४५ ॥ ४९६४ सनोतेरन इति च । ४९६५ सनोतेरन इति नियमार्थमिति चेत्सवनादिकृतत्वात्सिद्धम् । ४९६६ सनर्थं तु ॥

३ ११६ स्तम्भुसिवुसहां चङि २५८० ॥ ४९६७ स्तम्भुसिवुसहां चङ्युपसर्गात् ॥

३ । ११८ सदेः परस्य लिटि २३६१ ॥ ४९६८ सदो लिटि प्रतिषेधे स्वञ्जेरुपसंख्यानम् ॥

४ । १ रषाभ्यां नो णः समानपदे २३५ ॥ ४९६९ रषाभ्यां णत्व ऋकारग्रहणम् ॥

४ । २ अट्कुप्वाङ्नुम्व्यवायेऽपि १९७ ॥ ४९७० अड्व्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः । ४९७१ न वान्येन व्यपेतत्वात् । ४९७२ तत्समुदाये णत्वाप्रसिद्धिर्यथान्यत्र ।

४९७३ कुप्व्यवाये ह्रादेशेषु प्रतिषेधः । ४९७४ प्रयोजनं वृत्रघ्नः स्रुघ्नः प्राघानीति । ४९७५ नुम्व्यवाये णत्वेऽनुस्वाराभावे प्रतिषेधः । ४९७६ अनागमे च णत्वम् । ४९७७ अनुस्वारव्यवायवचनात्तु सिद्धम् ॥

४ । ३ पूर्वपदात्संज्ञायामगः ८५७ ॥ ४९७८ पूर्वपदात्संज्ञायामुत्तरपदग्रहणम् । ४९७९ तद्धितपूर्वपदस्थाप्रतिषेधार्थम् । ४९८० संज्ञायां नियमवचने गप्रतिषेधान्नियमप्रतिषेधः । ४९८१ तत्र नित्यं णत्वप्रसङ्गः । ४९८२ योगविभागात्सिद्धम् । ४९८३ अप्रतिषेधो वा यथा सर्वनामसंज्ञायाम् ॥

४ । ६ विभाषौषधिवनस्पतिभ्यः १०५१ ॥ ४९८४ 'द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम् । ४९८५ इरिकादिभ्यः प्रतिषेधो वक्तव्यः ॥

४ । ७ अह्नोऽदन्तात् ७९१ ॥ ४९८६ अदन्तादन्तस्येति वक्तव्यम् ॥

४ । ८ वाहनमाहितात् १०५२ ॥ ४९८७ आहितोपस्थितयोरिति वक्तव्यम् । ४९८८ वाहनं वाह्यादिति वक्तव्यम् ॥

४ । १० वा भावकरणयोः १०५४ ॥ ४९८९ वाप्रकरणे गिरिनद्यादीनामुपसंख्यानम् ॥

४ । ११ प्रातिपदिकान्तनुम्विभक्तिषु च १०५५ ॥ ४९९० प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणमसमासान्तप्रतिषेधार्थम् । ४९९१ तत्र युवादिप्रतिषेधः ॥

४ । १४ उपसर्गादसमासेऽपि णोपदेशस्य २२८७ ॥ ४९९२ णोपदेशं प्रत्युपसर्गभावादनिर्देशः । ४९९३ वचनप्रामाण्यादिति चेत्पदलोपे प्रतिषेधः । ४९९४ सिद्धं तु यं प्रत्युपसर्गस्तत्स्थस्येति वचनात् ॥

४ । १५ हिनुमिना २५३० ॥ ४९९५ हिनुमिनाग्रहणे विकृतस्योपसंख्यानम् । ४९९६ सिद्धमचः स्थानिवत्त्वात् ॥

४ । १६ आनि लोट् २२३१ ॥ ४९९७ आनि लोड्ग्रहणानर्थक्यमर्थवद्ग्रहणात् । ४९९८ अनुपसर्गाद्वा ॥

४ । १७ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च २२८९ ॥ ४९९९ नेर्गदादिष्वड्व्यवाय उपसंख्यानम् ॥

४ । १९-२० अनितेः २४७८ । अन्तः २९८४ ॥ ५००० अनितेरन्तग्रहणं संबुद्ध्यर्थम् । ५००१ यो वा तस्मादनन्तरः ॥

४ । २१ उभौ साभ्यासस्य २६०६ ॥ ५००२ साभ्यासस्य द्वयोरिष्टम् ॥

४ । २८ उपसर्गाद्बहुलम् ८५९ ॥ ५००३ भाविन्यप्योति नेष्यते ॥

४ । २९ कृत्यचः २८३५ ॥ ५००४ कृत्स्थस्य णत्वे निर्विण्णस्योपसंख्यानम् ॥

४ । ३० णेर्विभाषा २८३६ ॥ ५००५ णेर्विभाषायां साधनव्यवाय उपसंख्यानम् । ५००६ तद्विधानात्सिद्धम् । ५००७ अडधिकाराद्वा ॥

४ । ३२ इजादेः सनुमः २८३८ ॥ ५००८ सनुमो णत्वेऽवधारणाप्रसिद्धिर्विधेयभावात् । ५००९ सिद्धं तु प्रतिषेधाधिकारे सनुंग्रहणात् । ५०१० कृत्स्थस्य च णत्वे इजादेः सनुमो ग्रहणम् ॥

४ । ३४ न भाभूपूकमिगमिप्यायीवेपाम् २८४० ॥ ५०११ भादिषु पूञ्ग्रहणम् । ५०१२ ण्यन्तस्य चोपसंख्यानम् ॥

४ । ३५ षात्पदान्तात् ३३१० ॥ ५०१३ षात्पदादिपरवचनम् ॥

४ । ३६ नशेः षान्तस्य २५१८ ॥ ५०१४ नशेरशः ॥

४ । ३८ पदव्यवायेऽपि १०५७ ॥ ५०१५ पदव्यवायेऽतद्धिते ॥

४ । ४२ न पदान्ताट्टोरनाम् ११४ ॥ ५०१६ अनाम्नवतिनगरीणामिति वक्तव्यम् ॥

४ । ४५ यरोऽनुनासिकेऽनुनासिको वा ११६ ॥ ५०१७ यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनम् ॥

४ । ४७ अनचि च ४८ ॥ ५०१८ द्विर्वचने यणो मयः । ५०१९ शरः खयः । ५०२० अवसाने च ॥

४ । ४८ नादिन्याक्रोशे पुत्रस्य ५५ ॥ ५०२१ नादिन्याक्रोशे पुत्रस्येति तत्परे च । ५०२२ वा हतजग्धपरे च । ५०२३ चयो द्वितीयाः शरि पौष्करसादेः ॥

४ । ६१ उदः स्थास्तम्भोः पूर्वस्य ११८ ॥ ५०२४ उदः पूर्वत्वे स्कन्देश्छन्दस्युपसंख्यानम् ॥

४ । ६३ शश्छोऽटि १२० ॥ ५०२५ छत्वममि तच्छ्लोकेन तच्छ्मश्रुणेति प्रयोजनम् ॥

४ । ६५ झरो झरि सवर्णे ७१ ॥ ५०२६ झरो झरि सवर्णग्रहणं समसंख्यप्रतिषेधार्थम् ।

४ । ६८ अ अ ११ ॥ ५०२७ आदेशार्थं सवर्णार्थमकारो विवृतः स्मृतः । ५०२८ आकारस्य तथा ह्रस्वस्तदर्थं पाणिनेर अ । ५०२९ अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । ५०३० आदेशस्य चानण्त्वात्र सवर्णग्रहणम् । ५०३१ सिद्धं तु तपरनिर्देशात् । ५०३२ एकशेषनिर्देशाद्वा स्वरभिन्नानां भगवतः पाणिनेः सिद्धम् ॥

इत्यष्टमोऽध्यायः ।

परिशिष्टवार्तिकानि कैयटाद्युक्तानि ।

५०३३ पाशकल्पककाम्येष्विति वाच्यम् १९२ । ५०३४ गतिकारकेतरपूर्वपदस्य यण् नेष्यते २७२ । ५०३५ ओतो णिदिति वाच्यम् २८५ । ५०३६ रादेशात्पूर्वविप्रतिषेधेन नुम् ३०० । ५०३७ उशनसेः संबुद्धौ वानङ् नलोपश्च वा वाच्यः ४३६ । ५०३८ त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम् ४८६ । ५०३९ श्वशुरस्योकाराकारलोपश्च ५२३ । ५०४० अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया ५६८ । ५०४१ गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम् ५९४ । ५०४२ गुणकर्मणि वेष्यते ६२३ । ५०४३ सामान्ये नपुंसकम् ८२१ । ५०४४ मिथोऽनयोः समासे संख्या पूर्वं शब्दपरविप्रतिषेधात् ८९८ । ५०४५ अवर्णान्ताद्वा ९४१ । ५०४६ कृष्णोदकपाण्डुसंख्यापूर्वाया भूमेरच् ९४३ । ५०४७ संख्याया नदीगोदावरीभ्यां च ९४३ । ५०४८ कारके छे च न निषेधः १०२५ । ५०४९ शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः १०४९ । ५०५० त्यदादीनां फिञ्वा वाच्यः ११८० । ५०५१ दोश्च उपसंख्यानम् १२२१ । ५०५२ एकाचो नित्यम् १९२४ । ५०५३ अर्णसो लोपश्च १९२६ । ५०५४ ऋवर्णादपि २०३५ । ५०५५ अव्ययस्य च्वावीत्वं नेति वाच्यम् २११८ । ५०५६

संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगः २१४७। ५०५७ क्लित्यजादौ वा २४७३। ५०५८ सनि ण्वुलि ल्युटि च न २४८३। ५०५९ तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः २६२१। ५०६० व्रताद्भोजनतन्निवृत्त्योः २६७७। ५०६१ वस्त्रात्समाच्छादने २६७७। ५०६२ हल्यादिभ्यो ग्रहणे २६७७। ५०६३ सृजेः श्रद्धोपपन्ने कर्तर्येव २७६९। ५०६४ अग्रग्रामाभ्यां नयतेर्णो वाच्यः २९७५। ५०६५ सोपसर्गस्य न ३०७२। ५०६६ झलादाविति वक्तव्यम् ३३३०॥

इति कात्यायनप्रणीतो वार्तिकपाठः समाप्तः।

---

(७) परिभाषापाठः।

१ व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्। २ यथोद्देशं संज्ञापरिभाषम्। ३ कार्यकालं संज्ञापरिभाषम्। ४ अनेकान्ता अनुबन्धाः। ५ एकान्ताः। ६ नानुबन्धकृतमनेकाल्त्वम्। ७ नानुबन्धकृतमनेजन्तत्वम्। ८ नानुबन्धकृतमसारूप्यम्। ९ कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः। १० उभयगतिरिह भवति। ११ कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते। १२ यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते। १३ निर्दिश्यमानस्यादेशा भवन्ति। १४ यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः। १५ अर्थवद्ग्रहणे नानर्थकस्य। १६ गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः। १७ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति। १८ एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः, सह वा निवृत्तिः। १९ एकयोगनिर्दिष्टानां क्वचिदेकदेशोऽप्यनुवर्तते। २० भाव्यमानेन सवर्णानां ग्रहणं न। २१ भाव्यमानोऽप्युकारः सवर्णान्गृह्णाति। २२ वर्णाश्रये नास्ति प्रत्ययलक्षणम्। २३ उणादयोऽव्युत्पन्नानि प्रातिपदिकानि। २४ प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्। २५ प्रत्ययग्रहणे चापञ्चम्याः। २६ उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्। २७ स्त्रीप्रत्यये चानुपसर्जने न। २८ संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति। २९ कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्। ३० पदाङ्गाधिकारे तस्य च तदन्तस्य च। ३१ व्यपदेशिवदेकस्मिन्। ३२ ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति। ३३ व्यपदेशिवद्भावोऽप्रातिपदिकेन। ३४ यस्मिन्विधिस्तदादावल्ग्रहणे। ३५ सर्वो द्वन्द्वो विभाषैकवद्भवति। ३६ सर्वे विधयश्छन्दसि विकल्प्यन्ते। ३७ प्रकृतिवदनुकरणं भवति। ३८ एकदेशविकृतमनन्यवत्। ३९ पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः। ४० पुनः प्रसङ्गविज्ञानात्सिद्धम्। ४१ सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव। ४२ विकरणेभ्यो नियमो बलीयान्। ४३ कृताकृतप्रसङ्गि नित्यम्। ४४ शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति। ४५ शब्दान्तरात्प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम्। ४६ लक्षणान्तरेण प्राप्नुवन्विधिरनित्यः। ४७ क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता। ४८ यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्। ४९ यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्। ५० स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यः। ५१ असिद्धं बहिरङ्गमन्तरङ्गे। ५२ नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः। ५३ अन्तरङ्गानपि विधीन्बहि-

रङ्गो लुग्बाधते । ५४ पूर्वोत्तरपदनिमित्तकार्यात्पूर्वमन्तरङ्गोऽप्येकादेशो न । ५५ अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते । ५६ वार्णादाङ्गं बलीयो भवति । ५७ अकृतव्यूहाः पाणिनीयाः । ५८ येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति । ५९ क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते । ६० पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् । ६१ मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोत्तरान् । ६२ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । ६३ पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । ६४ प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते । ६५ उपसंजनिष्यमाणनिमित्तोऽप्यपवाद उपसंजातनिमित्तमप्युत्सर्गं बाधत इति । ६६ अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते । ६७ अभ्यासविकारेषु बाध्यबाधकभावो नास्ति । ६८ ताच्छीलिकेषु वासरूपविधिर्नास्ति । ६९ क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति । ७० लादेशेषु वासरूपविधिर्नास्ति । ७१ उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । ७२ प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् । ७३ विभक्तौ लिङ्गविशिष्टाग्रहणम् । ७४ सूत्रे लिङ्गवचनमतन्त्रम् । ७५ नञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः । ७६ गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः । ७७ सांप्रतिकाभावे भूतपूर्वगतिः । ७८ बहुव्रीहौ तद्गुणसंविज्ञानमपि । ७९ चानुकृष्टं नोत्तरत्र । ८० स्वरविधौ व्यञ्जनमविद्यमानवत् । ८१ हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् । ८२ निरनुबन्धकग्रहणे न सानुबन्धकस्य । ८३ तदनुबन्धकग्रहणे नातदनुबन्धकस्य । ८४ क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते । ८५ समासान्तविधिरनित्यः । ८६ संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य । ८७ सांनियोगशिष्टानामन्यतरापाये उभयोरप्यपायः । ८८ ताच्छीलिके णेऽण्कृतानि भवन्ति । ८९ धातोः कार्यमुच्यमानं तत्प्रत्यये भवति । ९० तन्मध्यपतितस्तद्ग्रहणेन गृह्यते । ९१ लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य । ९२ प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम् । ९३ अङ्गवृत्ते पुनर्वृत्तावविधिः । ९४ संज्ञापूर्वकविधेरनित्यत्वम् । ९५ आगमशास्त्रमनित्यम् । ९६ गणकार्यमनित्यम् । ९७ अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् । ९८ नञ्घटितमनित्यम् । ९९ आतिदेशिकमनित्यम् । १०० सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान् । १०१ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् । १०२ विधौ परिभाषोपतिष्ठते नानुवादे । १०३ उपपदविभक्तेः कारकविभक्तिर्बलीयसी । १०४ अनन्त्यविकारेऽन्त्यसदेशस्य । १०५ नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे । १०६ प्रधानाप्रधानयोः प्रधाने कार्यसंप्रत्ययः । १०७ अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी । १०८ व्यवस्थितविभाषयापि कार्याणि क्रियन्ते । १०९ विधिनियमसंभवे विधिरेव ज्यायान् । ११० सामान्यातिदेशे विशेषानतिदेशः । १११ प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् । ११२ सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम् । ११३ श्रुतानुमितयोः श्रुतसंबन्धो बलीयान् । ११४ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् । ११५ गामादाग्रहणेष्वविशेषः । ११६ प्रत्येकं वाक्यपरिसमाप्तिः । ११७ क्वचित्समुदायेऽपि । ११८ अभेदका गुणाः । ११९ बाधकान्येव निपातनानि । १२० पर्जन्यवल्लक्षणप्रवृत्तिः । १२१ लक्ष्ये लक्षणं सकृदेव प्रवर्तते । १२२ निषेधाश्च बलीयांसः । १२३ अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे । १२४ योगविभागादिष्टसिद्धिः । १२५ पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते । १२६ ज्ञापकसिद्धं न सर्वत्र । १२७ पूर्वत्रासिद्धी

यमद्वित्वे। १२८ एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति। १२९ संप्रसारणं तदाश्रयं च कार्यं बलवत्। १३० क्वचिद्विकृतिः प्रकृतिं गृह्णाति। १३१ औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्। १३२ श्तिपा शपानुबन्धेन निर्दिष्टं यद्गणेन च। यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि। १३३ पदगौरवाद्योगविभागो गरीयान्। १३४ अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः॥

इति परिभाषापाठः समाप्तः।

(८) शाकटायनप्रणीत उणादिसूत्रपाठः।

१ कृवापाजिमिस्वदिसाध्यशूभ्य उण्। २ छन्दसीणः। ३ दृसनिजनिचरिचटिभ्यो ञुण्। ४ किंजरयोः श्रिणः। ५ त्रो रश्च लः। ६ कृके वचः कश्च। ७ भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः। ८ अणश्च। ९ धान्ये नित्। १० शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च। ११ स्यन्देः संप्रसारणं धश्च। १२ उन्देरिच्चादेः। १३ ईषेः किच्च। १४ स्कन्देः सलोपश्च। १५ सृजेरसुम्च। १६ कृतेराद्यन्तविपर्ययश्च। १७ नावञ्चेः। १८ फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च। १९ वलेर्गुक्च। २० शः कित्सन्वच्च। २१ यो द्वे च। २२ कुर्भश्च। २३ पृभिदिव्यधिगृधिधृषिभ्यः। २४ कृग्रोरुच्च। २५ अपदुःसुषु स्थः। २६ रपेरिच्चोपधायाः। २७ अर्जिदृशिकम्यमिपशिबाधामृजिपशितुग्धुग्दीर्घहकारश्च। २८ प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च। २९ लङ्घिबंह्योर्नलोपश्च। ३० ऊर्णोतेर्नुलोपश्च। ३१ महति ह्रस्वश्च। ३२ श्लिषेः कश्च। ३३ आङ्परयोः खनिशॄभ्यां डिच्च। ३४ हरिमितयोर्द्रुवः। ३५ शते च। ३६ खरुशङ्कुपीयुनीलङ्गुलिगु। ३७ मृगय्वादयश्च। ३८ मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्। ३९ व्यथेः संप्रसारणं किच्च। ४० मुकुरदर्दुरौ। ४१ मद्गुरादयश्च। ४२ असेरुरन्। ४३ मसेश्च। ४४ शावशेराप्तौ। ४५ अविमह्योष्टिषच्। ४६ अमेर्दीर्घश्च। ४७ रुहेर्वृद्धिश्च। ४८ तवेर्णिद्वा। ४९ नञि व्यथेः। ५० किलेर्बुक्च। ५१ इषिमदिमुदिखिदिछिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिवन्धिशुषिभ्यः किरच्। ५२ अशेर्णित्। ५३ अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः। ५४ सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्। ५५ कमेः पश्च। ५६ गुपादिभ्यः कित्। ५७ मिथिलादयश्च। ५८ पतिकठिकुठिगडिगुडिदंशिभ्य एरक्। ५९ कुम्बेर्नलोपश्च। ६० शदेस्त च। ६१ मूलेरादयः। ६२ कबेरोतच्पश्च। ६३ भातेर्डवतुः। ६४ कठिचकिभ्यामोरन्। ६५ किशोरादयश्च। ६६ कपिगडिगण्डिकटिपटिभ्य ओलच्। ६७ मीनातेरुरन्। ६८ स्यन्देः संप्रसारणं च। ६९ सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्। ७० पः किच्च। ७१ अर्तेश्च तुः। ७२ कमिमनिजनिगाभायाहिभ्यश्च। ७३ चायः किः। ७४ आप्नोतेर्ह्रस्वश्च। ७५ वसेस्तुन्। ७६ अगारे णिच्च। ७७ कृञः कतुः। ७८ एधिवह्योश्चतुः। ७९ जीवेरातुः। ८० आतृकन्वृद्धिश्च। ८१ कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः। ८२ मृजेर्गुणश्च। ८३ वहो धश्च। ८४ कषेश्छश्च। ८५ णित्कसिपद्यर्तेः। ८६ अणो डश्च। ८७ नञि लम्बेर्नलोपश्च। ८८ के श्र एरङ् चास्य। ८९

ञो हुट् च । ९० दरिद्रातेर्यालोपश्च । ९१ नृतिशृध्योः कूः । ९२ ऋतेरम्च । ९३ अन्दूदृम्भूज-
म्बूकफेलूकर्कन्धूदिधिषूः । ९४ मृग्रोरुतिः । ९५ ग्रो मुट् च । ९६ हृषेरुलच् । ९७ हसृरु-
हियुषिभ्य इतिः । ९८ ताडेर्णिलुक् च । ९९ शमेर्ढः । १०० कमेरठः । १०१ रमेर्वृद्धिश्च ।
१०२ शमेः खः । १०३ कणेष्ठः । १०४ कलस्तृपश्च । १०५ शपेर्वश्च । १०६ वृषादिभ्यश्चित् ।
१०७ मृजेष्टिलोपश्च । १०८ चुपेरच्चोपधायाः । १०९ शाकिशम्योर्नित् । ११० छो गुग्घ्रस्वश्च ।
१११ जमन्ताड्डः । ११२ क्वादिभ्यः कित् । ११३ स्थाचतिमृजेरालज्वालञालीयचः । ११४
पतिचण्डिभ्यामालञ् । ११५ तमिविशिबिडिमृणिकुलिकपिपालिपाञ्चिभ्यः कालन् । ११६ पते-
रङ्ग्च्याक्षिणि । ११७ तरत्यादिभ्यश्च । ११८ विडादिभ्यः कित् । ११९ सृवृञोर्वृद्धिश्च । १२०
गन्गम्यद्योः । १२१ छापूखडिभ्यः कित् । १२२ भृञः किन्नुट् च । १२३ शृणातेर्ह्रस्वश्च ।
१२४ गणशकुनौ । १२५ मुदिग्रोर्गग्गौ । १२६ अण्डन्कृसृभृवृञः । १२७ शृदृभसोऽदिः । १२८
दृणातेः षुग्घ्रस्वश्च । १२९ त्यजितनियजिभ्यो डित् । १३० एतेस्तुट् च । १३१ सर्तेरटिः ।
१३२ लङ्घेर्नलोपश्च । १३३ पारयतेरजिः । १३४ प्रथः कित्संप्रसारणं च । १३५ भियः षुग्घ्र-
स्वश्च । १३६ युष्यासिभ्यां मदिक् । १३७ अर्तिस्तुसुहुसृधृक्षिक्षुभायावापदियक्षिनीभ्यो मन् ।
१३८ जहातेः सन्वदालोपश्च । १३९ अवतेष्टिलोपश्च । १४० ग्रसेरा च । १४१ अविसिविसि-
शुषिभ्यः कित् । १४२ इषियुधीन्धिदसिश्याधूसूभ्यो मुक् । १४३ युजिरुचितिजां कुश्च ।
१४४ हन्तेर्हि च । १४५ भियः षुग्वा । १४६ घर्मः । १४७ ग्रीष्मः । १४८ प्रथेः षिवन्संप्र-
सारणं च । १४९ अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् । १५० इण्शीभ्यां वण् । १५१ सर्व-
नीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे । १५२ शेवयह्वजिह्वाग्रीवाप्वमीवाः । १५३ कृगृशृ-
दृभ्यो वः । १५४ कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः । १५५ सप्यशूभ्यां तुट् च । १५६ नञि
जहातेः । १५७ श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्मन्मातरिश्वन्मघव-
न्निति ॥ इत्युणादिषु प्रथमः पादः ॥

१५८ कृहृभ्यामेणुः । १५९ हनिकुषिनीरमिकाशिभ्यः क्थन् । १६० अवे भृञः । १६१ उषिकु-
षिगार्तिभ्यस्थन् । १६२ सर्तेर्णित् । १६३ जृवृभ्यामूथन् । १६४ पातृतुदिवचिरिचिसिचिभ्यस्थ-
क् । १६५ अर्तेर्निरि । १६६ निशीथगोपीथावगथाः । १६७ गश्चोदि । १६८ समीणः । १६९ तिथपृ-
ष्ठगूथयूथप्रोथाः । १७० स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनी-
पदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् ।
१७१ चकिरम्योरुच्चोपधायाः । १७२ वौ कसेः । १७३ अमितम्योर्दीर्घश्च । १७४ निन्देर्नलोपश्च ।
१७५ अर्देर्दीर्घश्च । १७६ शुचेर्दश्च । १७७ दुरीणो लोपश्च । १७८ कृतेच्छः क्रू च । १७९ रोदेर्णि-
लुक् च । १८० बहुलमन्यत्रापि संज्ञाछन्दसोः । १८१ जोरी च । १८२ सुसूधागृधिभ्यः क्रन् ।
१८३ शुसिचिमीनां दीर्घश्च । १८४ वाविन्धेः । १८५ वृधिवपिभ्यां रन् । १८६ ऋज्रेन्द्राग्रवज्र-
विप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवन्रेरामालाः । १८७ समि कस उकन् । १८८
पचिनशोर्णुकन्कनुमौ च । १८९ भियः क्रुकन् । १९० कुन्शिल्पिसंज्ञयोरपूर्वस्यापि । १९१ रमे
रश्च लो वा । १९२ जहातेर्द्वे च । १९३ ध्मो धम च । १९४ हनो वध च । १९५ बहुलमन्य-
त्रापि । १९६ कृषेर्वृद्धिश्चोदीचाम् । १९७ उदकं च । १९८ वृश्चिकृषोः किकन् । १९९ प्राडि
पणिकषः । २०० मुषेर्दीर्घश्च । २०१ स्यमेः संप्रसारणं च । २०२ क्रिय इकन् । २०३ आङि

पणिपानिपतिखनिभ्यः । २०४ श्यास्त्याहृञविभ्य इनच् । २०५ वृजेः किच्च । २०६ अजेरज च । २०७ बहुलमन्यत्रापि । २०८ द्रुदक्षिभ्यामिनन् । २०९ अर्तेः क्रिदिच्च । २१० वेपितुह्यो-र्ह्रस्वश्च । २११ तलिपुलिभ्यां च । २१२ गर्वेरत उच्च । २१३ रुहेश्च । २१४ महेरिनण्च । २१५ क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च । २१६ आप्नोतेर्ह्रस्वश्च । २१७ परौ व्रजेः षः पदान्ते । २१८ हुवः श्लुवच्च । २१९ स्रुवः कः । २२० चिक्च । २२१ तनोतेरनश्च वः । २२२ ग्लानुदिभ्यां डौः । २२३ च्विरव्ययम् । २२४ रातेर्डैः । २२५ गमेर्डोः । २२६ भ्रमेश्च डूः । २२७ दमेर्डोसिः । २२८ पणेरिज्यादेश्च वः । २२९ वशेः कित् । २३० भृञ ऊच्च । २३१ जसि-सहोरुरिन् । २३२ सुयुरुवृञो युच् । २३३ अशे रश च । २३४ उन्देर्नलोपश्च । २३५ गमेर्गश्च । २३६ बहुलमन्यत्रापि । २३७ रञ्जेः क्युन् । २३८ भूसूधूभ्रस्जिभ्यश्छन्दसि । २३९ कृपृवृजि-मन्दिनिधाञः क्युः । २४० धृषेर्धिष् च संज्ञायाम् । २४१ वर्तमाने पृषद्बृहन्महज्जगच्छतृवत् । २४२ संश्चत्तृपद्वेहत् । २४३ छन्दस्यसानच्शुजृभ्याम् । २४४ ऋञ्जिवृधिमन्दिसहिभ्यः कित् । २४५ अर्तेर्गुणः शुट् च । २४६ सम्यानच्स्तुवः । २४७ युधिबुधिदृशिभ्यः किच्च । २४८ हुर्छेः सनो लुक् छलोपश्च । २४९ श्वितेर्दश्च । २५० तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ । २५१ बहुलमन्यत्रापि । २५२ नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ । २५३ साव-सेर्ऋन् । २५४ यतेर्वृद्धिश्च । २५५ नञि च नन्देः । २५६ दिवेर्ऋः । २५७ नयतेर्डिच्च । २५८ सव्ये स्थश्छन्दसि । २५९ अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः । २६० आङि शुषेः सनश्छन्दसि । २६१ कृषेरादेश्च चः । २६२ अदेर्मुट् च । २६३ वृतेश्च । २६४ क्षिपेः किच्च । २६५ अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः । २६६ बृंहेर्नलोपश्च । २६७ द्युतेरिसिन्नादेश्च जः । २६८ वसौ रुचेः संज्ञायाम् । २६९ भुवः कित् । २७० सहो धश्च । २७१ पिबतेस्थुक् । २७२ जनेरुसिः । २७३ मनेर्धश्छन्दसि । २७४ अर्तिपृवपियजितनिध-नितपिभ्यो नित् । २७५ एतेर्णिच्च । २७६ चक्षेः शिच्च । २७७ मुहेः किच्च । २७८ बहुलम-न्यत्रापि । २७९ कृगॄशॄवृञ्चतिभ्यः ष्वरच् । २८० नौ सदेः ॥ इत्युणादिषु द्वितीयः पादः ॥

२८१ छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः । २८२ इण्सि-ञ्जिदीङुष्यविभ्यो नक् । २८३ फेनमीनौ । २८४ कृषेर्वर्णे । २८५ बन्धेर्ब्रधिबुधी च । २८६ धाप्वस्यज्यतिभ्यो नः । २८७ लक्षेरट् च । २८८ वनेरिच्चोपधायाः । २८९ सिवेष्टेर्यू च । २९० कृवृजृसिद्रुपन्यनिस्वपिभ्यो नित् । २९१ धेट इच्च । २९२ तृषिशुषिरसिभ्यः कित् । २९३ सुञो दीर्घश्च । २९४ रमेस्त च । २९५ रास्नासास्नास्थूणावीणाः । २९६ गादाभ्या-मिष्णुच् । २९७ कृत्यशूभ्यां क्स्नः । २९८ तिजेर्दीर्घश्च । २९९ श्लिषेरच्चोपधायाः । ३०० याजिमानिशुन्धिदसिजनिभ्यो युच् । ३०१ भुजिमृङ्भ्यां युक्त्युकौ । ३०२ सर्तेरयुः । ३०३ पानीविषिभ्यः पः । ३०४ च्युवः किच्च । ३०५ स्तुवो दीर्घश्च । ३०६ सुशृभ्यां निच्च । ३०७ कुयुभ्यां च । ३०८ खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः । ३०९ स्तनिहृषिपुषिगदिम-दिभ्यो णेरित्नुच् । ३१० कृहनिभ्यां क्त्नुः । ३११ गमेः सन्वच्च । ३१२ दाभाभ्यां नुः । ३१३ वचेर्गश्च । ३१४ धेट इच्च । ३१५ सुवः कित् । ३१६ जहातेर्द्वेऽन्तलोपश्च । ३१७ स्थो णुः । ३१८ अजिवृरीभ्यो निच्च । ३१९ विषेः किच्च । ३२० कृदाधारार्चिकलिभ्यः कः । ३२१ सृवृभृशुषिमुषिभ्यः कक् । ३२२ शुकवल्कोल्काः । ३२३ इण्भीकापाशल्यतिमर्चिभ्यः

कन् । ३२४ नौ हः । ३२५ नौ सदेर्डिच । ३२६ स्यमेरीट् च । ३२७ अजियुधुनीभ्यो
दीर्घश्च । ३२८ ह्रियो रश्च लो वा । ३२९ शकेरुनोन्तोन्त्युनयः । ३३० भुवो झिच् । ३३१
कन्युच्क्षिपेश्च । ३३२ अनुङ् नदेश्च । ३३३ कृवृदारिभ्य उनन् । ३३४ ग्रो रश्च लो वा । ३३५
क्षुधिपिशिमिथिभ्यः कित् । ३३६ फलेर्गुक्च । ३३७ अशेर्लशश्च । ३३८ अर्जेर्णिलुक्च । ३३९
तृणाख्यायां चित् । ३४० अर्तेश्च । ३४१ अजियमिशीङ्भ्यश्च । ३४२ वृतृवदिहनिकमिकषि-
भ्यः सः । ३४३ प्लुषेरच्चोपधायाः । ३४४ मनेर्दीर्घश्च । ३४५ अशेर्देवने । ३४६ स्नुव्रश्चिकृत्यु-
षिभ्यः कित् । ३४७ ऋषेर्जातौ । ३४८ उन्दिगुधिकुषिभ्यश्च । ३४९ गृधिपण्योर्दकौ च । ३५०
अशेः सरः । ३५१ वसेश्च । ३५२ संपूर्वाच्चित् । ३५३ कृधूमदिभ्यः कित् । ३५४ पते रश्च लः ।
३५५ तन्यृषिभ्यां क्सरन् । ३५६ पीयुक्कणिभ्यां कालन्ह्रस्वः संप्रसारणं च । ३५७ कटिकु-
षिभ्यां काकुः । ३५८ सर्तेर्दुक्च । ३५९ वृतेर्वृद्धिश्च । ३६० पर्दोर्नित्संप्रसारणमल्लोपश्च । ३६१
सृयुवचिभ्योन्युजागूजक्नुचः । ३६२ आनकः शीङ्भियः । ३६३ आणको लुधुशिङ्घिधा-
ञ्भ्यः । ३६४ उल्मुकदर्विहोमिनः । ३६५ ह्रियः कुक्रश्च लो वा । ३६६ हसिमृग्रिण्वामिदमि-
लूपूधुर्विभ्यस्तन् । ३६७ नञ्याप इट् च । ३६८ तनिमृङ्भ्यां किच्च । ३६९ अञ्जिघृसिभ्यः
क्तः । ३७० दुतनिभ्यां दीर्घश्च । ३७१ जेर्मूट् चोदात्तः । ३७२ लोष्टपलितौ । ३७३
हृश्याभ्यामितन् । ३७४ रुहे रश्च लो वा । ३७५ पिशेः किच्च । ३७६ श्रुदक्षि-
स्पृहिगृहिभ्य आय्यः । ३७७ दिधिषाय्यः । ३७८ वृञ एण्यः । ३७९ स्तुवः क्सेय्य-
श्छन्दसि । ३८० राजेरन्यः । ३८१ शॄरम्योश्च । ३८२ अर्तेर्निच । ३८३ पर्जन्यः ।
३८४ वदेरान्यः । ३८५ अमिनक्षियजिवधिपतिभ्योऽत्रन् । ३८६ गडेरादेश्च कः । ३८७ वृञश्चित् ।
३८८ सुविदेः कत्रन् । ३८९ कृतेर्नुम्च । ३९० भृमृदृशियजिपर्विपच्यमितमिनामिहर्येभ्योऽतच् ।
३९१ पृषिरञ्जिभ्यां कित् । ३९२ खलतिः । ३९३ शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः ।
३९४ भृञश्चित् । ३९५ रुदिविदिभ्यां ङित् । ३९६ उपसर्गे वसेः । ३९७ अत्यविचमितमिन-
मिरभिलभिनभितपिपातिपनिपणिमहिभ्योऽसच् । ३९८ वेञस्तुट् च । ३९९ वहियुभ्यां
णित् । ४०० वयश्च । ४०१ दिवः कित् । ४०२ कृशृशलिकलिगर्दिभ्योऽभच् । ४०३ ऋ-
षिवृषिभ्यां कित् । ४०४ रुषेर्नित्लुच्च । ४०५ रासिवल्लिभ्यां च । ४०६ जृविशिभ्यां झच् । ४०७
रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि । ४०८ तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च ।
४०९ हन्तेर्मुट् हि च । ४१० भन्देर्नलोपश्च । ४११ ऋच्छेररः । ४१२ अर्तिकमिभ्रमिचमि-
देविवासिभ्यश्चित् । ४१३ कुवः क्ररन् । ४१४ आङ्गिमादिमान्दिभ्य आरन् । ४१५ गडेः कड
च । ४१६ शृङ्गारभृङ्गारौ । ४१७ कञ्जिमृजिभ्यां चित् । ४१८ कमेः किदुच्चोपधायाः । ४१९
तुषारादयश्च । ४२० दीङो नुट् च । ४२१ सर्तेरपः षुक्च । ४२२ उषिकुटिदलिकचिखजि-
भ्यः कपन् । ४२३ क्वणेः संप्रसारणं च । ४२४ कपश्चाक्रवर्मणस्य । ४२५ विटपपिष्टपविशि-
पोलपाः । ४२६ वृतेस्तिकन् । ४२७ कृतिभिदिलतिभ्यः कित् । ४२८ इष्यशिभ्यां तकन् ।
४२९ इणस्तशन्तशसुनौ । ४३० वीपतिभ्यां तनन् । ४३१ दृदलिभ्यां भः । ४३२ अर्तिगृभ्यां
भन् । ४३३ इणः कित् । ४३४ असिसञ्जिभ्यां क्थिन् । ४३५ प्लुषिकुषिशुषिभ्यः क्सिः । ४३६
अशेर्नित् । ४३७ इषेः क्सुः । ४३८ अवितृस्तृतन्त्रिभ्य ईः । ४३९ यापोः किद्द्वे च । ४४०
लक्षेर्मुट् च ॥ इत्युणादिषु तृतीयः पादः ।

४४१ वातप्रमीः । ४४२ ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्याङ्किकुयुकृशिभ्यः कनिज्यतुजलिजिष्ठुजिष्ठाजिसन्स्यानिथिनुल्यसासानुकः । ४४३ भ्रः करन् । ४४४ पुषः कित् । ४४५ कलश्च । ४४६ गमेरिनिः । ४४७ आङि णित् । ४४८ भुवश्च । ४४९ प्रे स्थः । ४५० परमे कित् । ४५१ मन्थः । ४५२ पतस्थ च । ४५३ खजेराकः । ४५४ बलाकादयश्च । ४५५ पिनाकादयश्च । ४५६ कषिदूषिभ्यामीकन् । ४५७ अनिहृषिभ्यां किच्च । ४५८ चङ्कणः कङ्कणश्च । ४५९ शॄपॄवृञां द्वे रुक्चाभ्यासस्य । ४६० फर्फरीकादयश्च । ४६१ ईषेः किद्ध्रस्वश्च । ४६२ ऋजेश्च । ४६३ सर्तेर्नुम्च । ४६४ मृडः कीकन्कङ्कणौ । ४६५ अलीकादयश्च । ४६६ कृतॄभ्यामीषन् । ४६७ शॄपॄभ्यां किच्च । ४६८ अर्जेर्ऋज च । ४६९ अम्बरीषः । ४७० कॄशॄपॄकटिपटिशौटिभ्य ईरन् । ४७१ वशेः कित् । ४७२ कशेर्मुट् च । ४७३ कृञ उच्च । ४७४ घसेः किच्च । ४७५ गभीरगम्भीरौ । ४७६ विषा विहा । ४७७ पच एलिमच् । ४७८ शीङो धुक्लक्वलञ्वालनः । ४७९ मृकणिभ्यामूकोकणौ । ४८० वलेरूकः । ४८१ उलूकादयश्च । ४८२ शलिमण्डिभ्यामूकण् । ४८३ नियो मिः । ४८४ अर्तेरुच्च । ४८५ भुवः कित् । ४८६ अश्नोतेे रश्च । ४८७ दल्मिः । ४८८ वीज्याज्वरिभ्यो निः । ४८९ सृवृषिभ्यां कित् । ४९० अङ्गेर्नलोपश्च । ४९१ वहिश्रियुद्रुग्लाहात्वरिभ्यो नित् । ४९२ घृणिपृश्निपार्ष्णिचूर्णिभूर्णि । ४९३ वृदॄभ्यां विन् । ४९४ जॄशॄस्तॄजागृभ्यः क्विन् । ४९५ दिवो द्वे दीर्घश्चाभ्यासस्य । ४९६ कृविघृष्विच्छविस्थविकिकीदिवि । ४९७ पातेर्डतिः । ४९८ शकेर्ऋतिन् । ४९९ अमेरतिः । ५०० वहिवस्यर्तिभ्यश्चित् । ५०१ अञ्चेः को वा । ५०२ हन्तेरंह च । ५०३ रमेर्नित् । ५०४ सूङः क्रिः । ५०५ अदिशदिभूशुभिभ्यः क्रिन् । ५०६ वङ्क्र्यादयश्च । ५०७ राशदिभ्यां त्रिप् । ५०८ अदेस्त्रिनिश्च । ५०९ पतेरत्रिन् । ५१० मृकणिभ्यामीचिः । ५११ श्वयतेश्चित् । ५१२ वेञो डिच्च । ५१३ ऋहनिभ्यामूषन् । ५१४ पुरः कुषन् । ५१५ पॄनहिकलिभ्य उपच् । ५१६ पीयेरूषन् । ५१७ मस्जेर्नुम्च । ५१८ गडेश्च । ५१९ अर्तेररुः । ५२० कुटः किच्च । ५२१ शकादिभ्योऽटन् । ५२२ कृकदिकडिकटिभ्योऽम्बच् । ५२३ कदेर्णित्पक्षिणि । ५२४ कलिकर्योरमः । ५२५ कुणिपुल्योः किन्दच् । ५२६ कुपेर्वा वश्च । ५२७ नौ षञ्जेर्घथिन् । ५२८ उद्यतेश्चित् । ५२९ सर्तेर्णिच्च । ५३० खर्जिपिञ्जादिभ्य ऊरोलचौ । ५३१ कुवश्चट्दीर्घश्च । ५३२ समीणः । ५३३ सिवेष्टेरू च । ५३४ शमेर्वन् । ५३५ उल्वादयश्च । ५३६ स्थः स्तोऽम्बजबकौ । ५३७ शाशपिभ्यां ददनौ । ५३८ अब्दादयश्च । ५३९ वलिमलितनिभ्यः कयन् । ५४० वृहेः षुग्दुकौ च । ५४१ मिपीभ्यां रुः । ५४२ जम्वादयश्च । ५४३ रुशातिभ्यां क्रुन् । ५४४ जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्ताण्क्तिन्शक्स्यढडटाटचः । ५४५ अन्येभ्योऽपि दृश्यन्ते । ५४६ कुसेरुम्भोमेदेताः । ५४७ सानसिवर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः । ५४८ मूशक्यबिभ्यः क्लः । ५४९ माछासासिभ्यो यः । ५५० जनेर्यक् । ५५१ अघ्न्यादयश्च । ५५२ स्नामदिपद्यर्तिपॄशकिभ्यो वनिप् । ५५३ शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप् । ५५४ धाप्योः संप्रसारणं च । ५५५ अदेर्ध च । ५५६ प्र ईरशदोस्तुट् च । ५५७ सर्वधातुभ्य इन् । ५५८ हृपिषिरुहिवृतिविदिच्छिदिकीर्तिभ्यश्च । ५५९ इगुपधात्कित् । ५६० भ्रमेः संप्रसारणं च । ५६१ क्रमितमिशतिस्तम्भामत इच्च । ५६२ मनेरुच्च । ५६३ वर्णेर्वलिश्चाहिरण्ये । ५६४ वासिवापियजिराजिव्रजिसदि-

हनिवाशिवादिवारिभ्य इञ् । ५६५ नहो भश्च । ५६६ कृषेर्वृद्धिश्छन्दसि । ५६७ श्रः शकुनौ
५६८ कृञ उदीचां कारुषु । ५६९ जनिघसिभ्यामिण् । ५७० अज्यतिभ्यां च । ५७१ पादे च ।
५७२ आशिपणाय्योरुडायलुकौ च । ५७३ वातेर्डिच्च । ५७४ प्रे हरतेः कूपे । ५७५ नौ व्यो
यलोपः पूर्वस्य च दीर्घः । ५७६ समाने ख्यः स चोदात्तः । ५७७ आङि श्रिहनिभ्यां ह्रस्वश्च ।
५७८ अच इः । ५७९ खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च । ५८० वृते-
श्छन्दसि । ५८१ भुजेः किच्च । ५८२ कृगॄशॄपॄकुटिभिदिछिदिभ्यश्च । ५८३ कुडि-
कम्प्योर्नलोपश्च । ५८४ सर्वधातुभ्यो मनिन् । ५८५ बृंहेर्नोऽच्च । ५८६ आशि-
शकिभ्यां छन्दसि । ५८७ हृभृधृसृस्तृशॄभ्य इमनिच् । ५८८ जनिमृङ्भ्यामिमनिन् ॥
५८९ वेञः सर्वत्र । ५९० नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्ध्मामन् । ५९१ मिथुने मनिः ।
५९२ सातिभ्यां मनिन्मनिणौ । ५९३ हनिमशिभ्यां सिकन् । ५९४ कोररन् । ५९५ गिर
उडच् । ५९६ इन्देः कमिर्नलोपश्च । ५९७ कायतेर्डिमिः । ५९८ सर्वधातुभ्यः ष्ट्रन् । ५९९
भ्रस्जिगमिनमिहानिविश्यशां वृद्धिश्च । ६०० दिवेर्धु च । ६०१ उषिखनिभ्यां कित् । ६०२
सिविमुच्योष्टेरू च । ६०३ अमिचिमिदिशसिभ्यः क्त्रः । ६०४ पुवो ह्रस्वश्च । ६०५ स्त्यायते-
र्ड्रट् । ६०६ गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः । ६०७ हुयामाश्रुभसिभ्यस्त्रन् । ६०८ गमेरा
च । ६०९ दादिभ्यश्छन्दसि । ६१० भूवादिगृभ्यो णित्रन् । ६११ चरेर्वृत्ते । ६१२ अशित्रा-
दिभ्य इत्रोत्रौ । ६१३ अमेर्द्विषति चित् । ६१४ आ समिण्निकषिभ्याम् । ६१५ चितेः कणा
कश्च । ६१६ सूचेः स्मन् । ६१७ पातेर्डुम्सुन् । ६१८ रुचिभुजिभ्यां किष्यन् । ६१९ वसेस्तिः ।
६२० सावसेः । ६२१ वौ तसेः । ६२२ पादिप्रथिभ्यां नित् । ६२३ दृणातेर्ह्रस्वश्च । ६२४
कृतॄकृपिभ्यः कीटन् । ६२५ रुचिवचिकुचिकुटिभ्यः कितच् । ६२६ कुटिकुषिभ्यां क्मलन् ।
६२७ कुषेर्लेश्च । ६२८ सर्वधातुभ्योऽसुन् । ६२९ रपेरत एच्च । ६३० अशेर्देवने युट् च ।
६३१ उब्जेर्बले बलोपश्च । ६३२ श्वेः संप्रसारणं च । ६३३ श्रयतेः स्वाङ्गे शिरः किच्च । ६३४
अर्तेरुच्च । ६३५ व्याधौ शुट् च । ६३६ उदके नुट् च । ६३७ इण आगसि । ६३८ रिचे-
र्धने घिच्च । ६३९ चायतेरन्ने ह्रस्वश्च । ६४० वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च । ६४१
स्रुरीभ्यां तुट् च । ६४२ पातेर्बले जुट् च । ६४३ उदके थुट् च । ६४४ अन्ने च । ६४५
अदेर्नुम्धौ च । ६४६ स्कन्देश्च स्वाङ्गे । ६४७ आपः कर्माख्यायाम् । ६४८ रूपे जुट् च ।
६४९ उदके नुम्भौ च । ६५० नहेर्दिवि भश्च । ६५१ इण आगोऽपराधे च । ६५२ अमेर्हुक्च ।
६५३ रमेश्च । ६५४ देशेऽह च । ६५५ अञ्च्यञ्जियुजिभृजिभ्यः कुश्च । ६५६
भूरञ्जिभ्यां कित् । ६५७ वसेर्णित् । ६५८ चन्देरादेश्च छः । ६५९ पचिवचिभ्यां सुट्
च । ६६० वहिहाधाञ्भ्यश्छन्दसि । ६६१ इण आसिः । ६६२ मिथुनेऽसिः पूर्ववच्च सर्वम् ।
६६३ नञि हन एह च । ६६४ विधाञो वेध च । ६६५ नुवो धुट् च । ६६६ गतिकारकोप-
पदयोः पूर्वपदप्रकृतिस्वरत्वं च । ६६७ चन्द्रे मो डित् । ६६८ वयसि धाञः । ६६९ पयसि च ।
६७० पुरसि च । ६७१ पुरूरवाः । ६७२ चक्षेर्बहुलं शिच्च । ६७३ उषः कित् । ६७४ दमे-
रुनसिः । ६७५ अङ्गतेरसिरिरुडागमश्च । ६७६ सर्तेरप्पूर्वादसिः । ६७७ विदिभुजिभ्यां विश्वे ।
६७८ वशेः कनसिः ॥ इत्युणादिषु चतुर्थः पादः ॥
६७९ अदि भुवो डुतच् । ६८० गुधेरूमः । ६८१ मसेरूरन् । ६८२ स्थः किच्च । ६८३

पातेरतिः । ६८४ वातेर्नित् । ६८५ अर्तेश्च । ६८६ तृहेः क्नो हलोपश्च । ६८७ वृन्लुटितनिता-डिभ्य उलच्तण्डश्च । ६८८ दंसेष्टटनौ न आ च । ६८९ दंशेश्च । ६९० उदि चेर्डैसिः । ६९१ नौ दीर्घश्च । ६९२ सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः । ६९३ पूञो यण्णुक्ह्रस्वश्च । ६९४ स्रंसेः शि कुट् किच्च । ६९५ अर्तेः क्युरुच । ६९६ हिंसेरीरन्नीरचौ । ६९७ उदि दृणा-तेरजलौ पूर्वपदान्त्यलोपश्च । ६९८ डित्खनेर्मुट् स चोदात्तः । ६९९ अमेः सन् । ७०० मुहेः खो मूर्च । ७०१ नहेर्हलोपश्च । ७०२ शीङो ह्रस्वश्च । ७०३ माङ ऊखो मय् च । ७०४ कलि-गलिभ्यां फगस्योच । ७०५ स्पृशेः श्वण्शुनौ पृ च । ७०६ श्रमनि श्रयतेर्डुन् । ७०७ अश्वाद-यश्च । ७०८ जनेष्टन्लोपश्च । ७०९ अचतस्य जङ्घच् । ७१० हन्तेः शरीरावयवे द्वे च । ७११ क्लिशेरन्लो लोपश्च । ७१२ फलेरितजादेश्च पः । ७१३ कृञादिभ्यः संज्ञायां वुन् । ७१४ चीक-यतेराद्यन्तविपर्ययश्च । ७१५ पचिमच्योरिच्चोपधायाः । ७१६ जनेररष्ठ च । ७१७ वचिमनि-भ्यां चिच्च । ७१८ ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च । ७१९ कृदरादयश्च । ७२० हन्तेर्युगा-द्यन्तयोर्धत्वतत्वे । ७२१ क्रमिगमिक्षमिभ्यस्तुन्वृद्धिश्च । ७२२ हर्यतेः कन्यन्हिरच् । ७२३ कृञः पासः । ७२४ जनेस्तु रश्च । ७२५ ऊर्णोतेर्डः । ७२६ दधातेर्यन्नुट् च । ७२७ जीर्यतेः क्रिन्रश्च वः । ७२८ मव्यतेर्यलोपो मश्चापतुट् चालः । ७२९ ऋजेः कीकन् । ७३० तनोतेर्डउः सन्वच्च । ७३१ अर्भकपृथुकपाका वयसि । ७३२ अवद्यावमाधमार्वरेफाः कुत्सिते । ७३३ लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः । ७३४ क्लिशेरीच्चोपधायाः कन्लोपश्च लो नाम्च । ७३५ अश्नोतेराशुकर्मणि वरट् च । ७३६ चतेरुरन् । ७३७ प्रा(प्रेऽ)ततररन् । ७३८ अमेस्तु-ट् च । ७३९ दहेर्गो लोपो दश्च नः । ७४० सिचेः संज्ञायां हनुमौ कश्च । ७४१ व्याङि घ्रातेश्च जातौ । ७४२ हन्तेरच् घुरच् । ७४३ क्षमेरुपधालोपश्च । ७४४ तरतेर्ड्रिः । ७४५ ग्रहेरनिः । ७४६ प्रथेरमच् । ७४७ चरेश्च । ७४८ मङ्गेरलच् ॥ इत्युणादिषु पञ्चमः पादः ॥

इति शाकटायनप्रणीत उणादिसूत्रपाठः समाप्तः ।

---

(९) शान्तनवाचार्यप्रणीतः फिट्सूत्रपाठः ।

फिषोऽन्त उदात्तः । २ पाटलपालङ्काम्बासागरार्थानाम् । ३ गेहार्थानामस्त्रियाम् । ४ गुदस्य च । ५ ध्यपूर्वस्य स्त्रीविषयस्य । ६ खान्तस्याश्मादेः । ७ बंहिष्ठवत्सरतिशत्थान्ताना-म् । ८ दक्षिणस्य साधौ । ९ स्वाङ्गाख्यायामादिर्वा । १० छन्दसि च । ११ कृष्णस्यामृगा-ख्या चेत् । १२ वा नामधेयस्य । १३ शुक्लगौरयोरादिः । १४ अङ्गुष्ठोदकबकवशानां छन्द-स्यन्तः । १५ पृष्ठस्य च । १६ अर्जुनस्य तृणाख्या चेत् । १७ आर्यस्य स्वाम्याख्या चेत् । १८ आशाया अदिगाख्या चेत् । १९ नक्षत्राणामाब्विषयाणाम् । २० न कुपूर्वस्य कृत्तिका-ख्या चेत् । २१ घृतादीनां च । २२ ज्येष्ठकनिष्ठयोर्वयसि । २३ बिल्वतिष्ययोः स्वरितो वा ॥ इति फिट्सूत्रेषु प्रथमः पादः ॥

२४ अथादिः प्राक् शकटेः । २५ ह्रस्वान्तस्य स्त्रीविषयस्य । २६ नब्विषयस्यानिसन्तस्य । २७ तृणधान्यानां च द्व्यषाम् । २८ त्रः संख्यायाः । २९ स्वाङ्गशिटामदन्तानाम् । ३० प्राणिनां कुपूः

र्वम्। ३१ खय्युवर्णं कृत्रिमाख्या चेत्। ३२ उनर्वन्नन्तानाम्। ३३ वर्णानां तणतिनितान्तानाम्
३४ ह्रस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये। ३५ अक्षस्यादेवनस्य। ३६ अर्धस्यासमद्योतने। ३७ पीत-
द्रूर्थानाम्। ३८ ग्रामादीनां च। ३९ लुबन्तस्योपमेयनामधेयस्य। ४० न वृक्षपर्वतविशेषव्या-
घ्रसिंहमहिषाणाम्। ४१ राजविशेषस्य यमन्वा चेत्। ४२ लघावन्ते द्वयोश्च बह्वषो गुरुः। ४३
स्त्रीविषयवर्णाक्षुपूर्वाणाम्। ४४ शकुनीनां च लघु पूर्वम्। ४५ नर्तुप्राण्याख्यायाम्। ४६
धान्यानां च वृद्धक्षान्तानाम्। ४७ जनपदशब्दानामषान्तानाम्। ४८ हयादीनामसंयुक्तला-
न्तानामन्तः पूर्वं वा। ४९ इगन्तानां च द्व्यषाम्॥ इति फिट्सूत्रेषु द्वितीयः पादः॥

५० अथ द्वितीयं प्रागीषात्। ५१ त्र्यचां प्राङ्मकरात्। ५२ स्वाङ्गानामकुर्वादीनाम्।
५३ मादीनां च। ५४ शादीनां शाकानाम्। ५५ पान्तानां गुर्वादीनाम्। ५६ युतान्यण्यन्ता-
नाम्। ५७ मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा। ५८ छ-
न्दसि च। ५९ कर्दमादीनां च। ६० सुगन्धितेजनस्य ते वा। ६१ नपः फलान्तानाम्।
६२ यान्तस्यान्त्यात्पूर्वम्। ६३ थान्तस्य च नालघुनी। ६४ शिशुमारोदुम्बरबलीवर्दोष्ट्रार-
पुरूरवसां च। ६५ सांकाश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्। ६६ ईषान्तस्य हयादेरादि-
र्वा। ६७ उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणा-
म्। ६८ महिष्यषाढयोर्जायेष्टकाख्या चेत्॥ इति फिट्सूत्रेषु तृतीयः पादः॥

६९ शकटिशकट्योरक्षरमक्षरं पर्यायेण। ७० गोष्ठजस्य ब्राह्मणनामधेयस्य। ७१
पारावतस्योपोत्तमवर्जम्। ७२ धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्।
७३ कपिकेशहरिकेशयोश्छन्दसि। ७४ न्यङ्स्वरौ स्वरितौ। ७५ न्यर्बुदव्यल्कशयोरादिः।
७६ तिल्यशिक्यमर्त्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः। ७७ बिल्वभक्ष्यवीर्याणि छ-
न्दसि। ७८ त्वत्त्वसमसिमेत्यनुच्चानि। ७९ सिमस्याथर्वणेऽन्त उदात्तः। ८० निपाता आद्युदात्ताः।
८१ उपसर्गाश्चाभिवर्जम्। ८२ एवादीनामन्तः। ८३ वाचादीनामुभावुदात्तौ। ८४ चादयो-
ऽनुदात्ताः। ८५ यथेति पादान्ते। ८६ प्रकारादिद्विरुक्तौ। ८७ शेषं सर्वमनुदात्तम्॥ इति
फिट्सूत्रेषु चतुर्थः पादः॥

इति शान्तनवाचार्यप्रणीतः फिट्सूत्रपाठः।

अष्टाध्यायीस्थगणसूत्राणि।

१।१।२७ सर्वादीनि सर्वनामानि २१३॥ १ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यव-
स्थायामसंज्ञायाम्। २ स्वमज्ञातिधनाख्यायाम्। ३ अन्तरं बहिर्योगोपसंव्यानयोः॥

१।१।३७ स्वरादिनिपातमव्ययम् ४४७॥ ४ वत्। ५ क्त्वातोसुन्कसुनः। ६ कृन्मेजन्तः
संध्यक्षरान्तः। ७ अव्ययीभावश्च। ८ तसिलादयस्तद्धिता एधाच्पर्यन्ताः। ९ शस्तसी।
१० कृत्वसुच्। ११ सुच्। १२ आस्थालौ। १३ च्व्यर्थाश्च। १४ अम्। १५ आम्॥

१।४।५७ चादयोऽसत्त्वे २०॥ १६ उपसर्गविभक्तिस्वरप्रतिरूपकाश्च॥

२।१।१७ तिष्ठद्गुप्रभृतीनि च ६७१॥ १७ इच्॥

२।१।७२ मयूरव्यंसकादयश्च ७५४ ॥ १८ एहीडादयोऽन्यपदार्थे । १९ जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति । २० आख्यातमाख्यातेन क्रियासातत्ये ॥

२।४।५९ पैलादिभ्यश्च १०८४ ॥ २१ तद्राजाच्चाणः ॥

३।१।१३४ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः २८९६ ॥ २२ नन्दिवासि (शि)-मदिदूषिसाधिवर्धिशोभिरोचि(षि)भ्यो ण्यन्तेभ्यः संज्ञायाम् । २३ सहितपिदमः संज्ञायाम् । २४ रक्षश्रुवसवपशां नौ । २५ याचृव्याहृव्रजवदवसां प्रतिषिद्धानाम् । २६ अचामचित्तकर्तृकाणाम् । २७ विषयी देशे । २८ अभिभावी भूते ॥

३।३।१०४ षिद्भिदादिभ्योऽङ् ३२८१ ॥ (२९ भिदा विदारणे ।) (३० छिदा द्वैधीकरणे ।) (३१ गुहा गिर्योषध्योः ।) (३२ आरा शस्त्र्याम् ।) ३३ कारा बन्धने । ३४ तारा ज्योतिषि । (३५ धारा प्रपातने ।) ३६ क्रपेः संप्रसारणं च ॥

४।१।४ अजाद्यतष्टाप् ४५४ ॥ (३७ संभस्त्राजिनशणपिण्डेभ्यः फलात् ।) (३८ सच्काण्डप्रान्तशतैकेभ्यः पुष्पात् ।) (३९ शूद्रा चामहत्पूर्वा जातिः ।) (४० मूलान्नञः ।) (४१ त्रिफला द्विगौ ॥)

४।१।४१ षिद्गौरादिभ्यश्च ४९८ ॥ ४२ एषणः करणे । ४३ सुमङ्गलात्संज्ञायाम् । ४४ रोहिणी नक्षत्रे । ४५ रेवती नक्षत्रे । ४६ कटाच्छ्रोणिवचने । ४७ पिप्पल्यादयश्च ॥

४।१।४५ बह्वादिभ्यश्च ५०३ ॥ ४८ शक्तिः शस्त्रे । ४९ इतः प्राण्यङ्गात् । ५० कृदिकारादक्तिनः । ५१ सर्वतोऽक्तिन्नर्थात् । ५२ चन्द्रभागान्नद्याम् ॥

४।१।७३ शार्ङ्गरवाद्यञो ङीन् ५२७ ॥ ५३ भोगवद्गौरिमतोः संज्ञायां घादिषु नित्यं ह्रस्वार्थम् । ५४ नृनरयोर्वृद्धिश्च ॥

४।१।८० क्रौड्यादिभ्यश्च १२०० ॥ ५५ सूत युवत्याम् । ५६ भोज क्षत्रिये ॥

४।१।८६ उत्सादिभ्योऽञ् । १०७८ ॥ ५७ उदस्थान देशे । (५८ ग्रीष्मादच्छन्दसि ।)

४।१।९६ बाह्वादिभ्यश्च १०९६ ॥ ५९ अमितौजसः सलोपश्च । ६० उदक संज्ञायाम् । ६१ संभूयोम्भसोः सलोपश्च ॥

४।१।९९ नडादिभ्यः फक् ११०१ ॥ ६२ शलङ्कु शलङ्कं च । ६३ अग्निशर्मन् वृषगणे । ६४ कृष्णरणौ ब्राह्मणवासिष्ठे । ६५ क्रोष्टु क्रोष्टं च ॥

४।१।१०४ अनृष्यानन्तर्ये विदादिभ्योऽञ् ११०६ ॥ ६६ परस्त्री परशुं च ॥

४।१।१०५ गर्गादिभ्यो यञ् ११०७ ॥ ६७ वाजासे ॥

४।१।११० अश्वादिभ्यः फञ् १११३ ॥ ६८ शप आत्रेये । ६९ पुंसि जाते । ७० आत्रेय भारद्वाजे । ७१ भरद्वाज आत्रेये ।

४।१।११२ शिवादिभ्योऽण् १११८ ॥ ७२ द्व्यचो नद्याः । ७३ त्रिवेणी त्रिवणं च ॥

४।१।१२३ शुभ्रादिभ्यश्च ॥ ११२६ ॥ ७४ लक्ष्मणश्यामयोर्वासिष्ठे ॥

४।१।१५१ कुर्वादिभ्यो ण्यः ११७५ ॥ ७५ सम्राजः क्षत्रिये । ७६ वेनाच्छन्दसि ॥

४।१।१५८ वाकिनादीनां कुक् च ॥ ११८२ ॥ ७७ चर्मिवर्मिणोर्नलोपश्च ॥

---

१ २२–२३ सूत्रे नन्द्याद्यन्तर्गणसूत्रे । २ २४–२८ सूत्रे ग्रहाद्यन्तर्गणसूत्राणि । ३ एवं धनुराकारद्वयान्तर्गतानि वार्तिकेभ्यागतानीति गणपाठे प्रक्षिप्तानि भान्ति ।

४ । २ । ४९ खण्डिकादिभ्यश्च १२९४ ॥ ७८ क्षुद्रकमालवात्सेनासंज्ञायाम् (वा) ॥
४ । २ । ८० (पक्षादिभ्यः फक्) १२९२ ॥ ७९ पथि पन्थ च ॥
४ । २ । ९१ नडादीनां कुक् च १३१० ॥ ८० कुञ्चा ह्रस्वत्वं च । ८१ तक्षन्नलोपश्च ॥
४ । २ । ९५ कत्त्र्यादिभ्यो ढकञ् १३१९ ॥ ८२ कुड्याया यलोपश्च ॥
४ । २ । ९७ नद्यादिभ्यो ढक् १३१७ ॥ ८३ वडवाया वृषे ॥
४ । २ । ११६ काश्यादिभ्यष्ठञ्ञिठौ १३४० ॥ ८४ आपदादिपूर्वपदात्कालान्तात् ॥
४ । २ । १२७ धूमादिभ्यश्च १३५१ ॥ ८५ कूलात्सौवीरेषु । ८६ समुद्रान्नावि मनुष्ये च ॥
४ । २ । १३८ गहादिभ्यश्च १३६२ ॥ (८७ मध्य मध्यमं च अण् चरणे) । ८८ मुखपार्श्वतसोर्लोपश्च । ८९ जनपरयोः कुक् च । ९० देवस्य च । ९१ वेणुकादिभ्यश्छण् ॥
४ । ३ । १६ संधिवेलाद्यृतुनक्षत्रेभ्योऽण् ॥ ९२ संवत्सरात्फलपर्वणोः ॥
४ । ३ । ५४ दिगादिभ्यो यत् १४२९ ॥ ९३ उदकात्संज्ञायाम् ॥
४ । ३ । १५२ तालादिभ्योऽण् १५३० ॥ ९४ तालाद्धनुषि ॥
५ । १ । २ उगवादिभ्यो यत् १६६२ ॥ ९५ नाभि नभं च । ९६ शुनः संप्रसारणं वा च दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम् । ९७ ऊधसोऽनङ् च ॥
५ । १ । ४ विभाषा हविरपूपादिभ्यः १६६४ ॥ ९८ अन्नविकारेभ्यश्च ॥
५ । १ । ६४ छेदादिभ्यो नित्यम् १७२९ ॥ ९९ विराग विरङ्गं च ॥
५ । १ । १०१ तस्मै प्रभवति संतापादिभ्यः १७६५ ॥ १०० मांसौदनाद्विगृहीतादपि ॥
५ । १ । १२३ वर्णदृढादिभ्यः ष्यञ्च १७८७ ॥ १०१ वेर्यातलाभमतिमनःशारदानाम् । १०२ समो मतिमनसोः ॥
५ । १ । १२४ गुणवचनब्राह्मणादिभ्यः कर्मणि च १७८८ ॥ (१०३ अर्हतो नुम् च) । १०४ सर्ववेदादिभ्यः स्वार्थे । १०५ चतुर्वेदस्योभयपदवृद्धिश्च ॥
५ । १ । १२८ पत्यन्तपुरोहितादिभ्यो यक् १७९३ ॥ १०६ राजासे ॥
५ । १ । १२९ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् १७९४ ॥ १०७ सुभग मन्त्रे ॥
५ । १ । १३० हायनान्तयुवादिभ्योऽण् १७९५ ॥ १०८ पुरुषासे । १०९ हृदयासे (११० श्रोत्रियस्य यलोपश्च) ॥
५ । २ । ३६ तदस्य संजातं तारकादिभ्य इतच् १८३७ ॥ १११ गर्भादप्राणिनि ॥
५ । २ । ९५ रसादिभ्यश्च १८९५ ॥ ११२ गुणात् । ११३ एकाचः ॥
५ । २ । ९७ सिध्मादिभ्यश्च १९०४ ॥ ११४ पार्ष्णिधमन्योर्दीर्घश्च । ११५ वातदन्तबल-ललाटगलानामूङ् च । ११६ जटाघटाकालाः क्षेपे । ११७ क्षुद्रजन्तूपतापयोश्च ॥
५ । २ । १०० लोमादिपामादिपिच्छादिभ्यः शनेलचः १९०७ ॥ ११८ अङ्गात्कल्याणे । ११९ शाकीपलाली-(दर्द्रूणां) ह्रस्वत्वं च । (१२० विष्वगित्युत्तरपदलोपश्चाकृतसंधेः ।) १२१ लक्ष्म्या अच्च । १२२ जटाघटाकालाः क्षेपे ॥
५ । २ । ११६ व्रीह्यादिभ्यश्च १९२३ ॥ १२३ शीर्षान्नञः ॥
५ । २ । ११७ तुन्दादिभ्य इलच्च १९२१ ॥ १२४ स्वाङ्गाद्विवृद्धौ ॥

५ । २ । १२७ अर्शआदिभ्योऽच् १९३३ ॥ १२५ स्वाङ्गाद्धीनात् । १२६ वर्णात् ॥

५ । २ । १३१ सुखादिभ्यश्च १९३७ ॥ १२७ माला क्षेपे ॥

५ । ४ । ३ स्थूलादिभ्यः प्रकारवचने कन् २०७९ ॥ १२८ कृष्ण तिलेषु । १२९ यव व्रीहिषु । १३० इक्षुतिलपाद्यकालावदाताः सुरायाम् । १३१ गोमूत्र आच्छादने । १३२ सुरा अहौ । १३३ जीर्ण शालिषु । १३४ पत्रमूले समस्तव्यस्ते ॥

५ । ४ । २९ यावादिभ्यः कन् २०९७ ॥ १३५ ऋतावुष्णशीते । १३६ पशौ लूनवियाते । १३७ अणु निपुणे । १३८ पुत्र कृत्रिमे । १३९ स्नात वेदसमाप्तौ । १४० शून्य रिक्ते । १४१ दान कुत्सिते । १४२ तनु सूत्रे । १४३ ईयसश्च ॥

५ । ४ । ३४ विनयादिभ्यष्ठक् २१०२ ॥ १४४ उपायो ह्रस्वत्वं च ॥

५ । ४ । ३८ प्रज्ञादिभ्यश्च २१०६ ॥ १४५ श्रोत्र शरीरे । १४६ कृष्ण मृगे ॥

५ । ४ । १०७ अव्ययीभावे शरत्प्रभृतिभ्यः ६७७ ॥ १४७ जराया जरस् च । १४८ प्रतिपरसमनुभ्योऽक्ष्णः ॥

५ । ४ । १५१ उरःप्रभृतिभ्यः कप् ८८९ ॥ १४९ अर्थान्नञः ॥

६ । १ । ९७ शकन्ध्वादिषु पररूपं वाच्यम् (वा ३६३२) ॥ १५० सीमन्तः केशवेषेषु । १५१ सारङ्गः पशुपक्षिणोः ॥

६ । १ । १५७ पारस्करप्रभृतीनि च संज्ञायाम् १०७१ ॥ १५२ पारस्करो देशः । १५३ कारस्करो वृक्षः । १५४ रथस्था नदी । १५५ किष्कुः प्रमाणम् । १५६ किष्किन्धा गुहा । (१५७ तद्बृहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च ।) १५८ प्रात्तुम्पतौ गवि कर्तरि ॥

६ । १ । १६० उञ्छादीनां च ३६८१ ॥ १५९ युग कालविशेषे रथाद्युपकरणे च ॥ १६० गरो दूष्येऽबन्तः । १६१ वेदवेगवेष्टबन्धाः करणे । १६२ स्तुयुद्रुवश्छन्दसि । १६३ वर्तनिः स्तोत्रे । १६४ श्वभ्रे दरः । १६५ साम्बतापौ भावगर्हायाम् । १६६ उत्तमशश्वत्तमौ सर्वत्र । १६७ भक्षमन्थभोगमन्थाः (देहाः) ॥

६ । १ । २०३ वृषादीनां च ३६९१ ॥ १६८ शमरणौ संज्ञायां संमतौ भावगर्हायाम् ॥

६ । २ । ८१ युक्तारोह्यादयश्च ३८१५ ॥ १६९ पात्रेसमितादयश्च ॥

६ । २ । १४६ संज्ञायामनाचितादीनाम् ३८८० ॥ १७० संहितागवि ॥

६ । २ । १४७ प्रवृद्धादीनां च ३८८१ ॥ १७१ प्रवृद्धं यानम् । १७२ प्रवृद्धो वृषलः । १७३ प्रयुक्ताः सूक्तवः । १७४ आकर्षेऽवहितः । १७५ अवहितो भोगेषु ॥

६ । २ । १६० कृत्योकेष्णुच्चार्वादयश्च ३८९४ ॥ १७६ वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम् । १७७ विकारसदृशे व्यस्तसमस्ते । १७८ राजाह्नोश्छन्दसि ॥

६ । २ । १८४ निरुदकादीनि च ३९१८ ॥ १७९ परेर्हस्तपादकेशकर्षाः ।

७ । ३ । ५३ न्यङ्क्वादीनां च २८६५ ॥ १८० संज्ञायां मेघनिदाघावदाघार्घाः ॥

८ । ३ । ९८ सुषामादिषु च १०२२ ॥ १८१ गौरिसक्थः संज्ञायाम् । १८२ प्रति संज्ञायामगात् । १८३ नक्षत्राद्वा ॥

८। ३। ३९ क्षुभ्नादिषु च ७९२ ॥ १८४ आचार्योदणत्वं च । १८५ इरिकादीनि वनोत्तरपदानि संज्ञायाम् ॥ इत्यष्टाध्यायीस्थगणसूत्राणि ॥

धातुपाठान्तर्गणसूत्राणि ।

१८६ घटादयः षितः । १८७ घटादयो मितः । १८८ जनीजॄष्क्नसुरञ्जोऽमन्ताश्च । १८९ ज्वलह्वलह्मलनमामनुपसर्गाद्वा । १९० ग्लास्नावनुवमां च । १९१ न कम्यमिचमां च । १९२ शमोऽदर्शने । १९३ यमोऽपरिवेषणे । १९४ स्खदिरवपरिभ्यां च । १९५ चर्करीतं च । १९६ स्वादय ओदितः । १९७ छन्दसि । १९८ नान्ये मितोऽहेतौ । १९९ कुस्म नाम्नो वा । २०० हन्त्यर्थाश्च । २०१ आ स्वदः सकर्मकात् । २०२ आधृषाद्वा । २०३ प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । २०४ तत्करोति तदाचष्टे । २०५ तेनातिक्रामति । २०६ धातुरूपं च । २०७ कर्तृकरणाद्धात्वर्थे । २०८ बहुलमेतन्निदर्शनम् । २०९ णिङङ्गान्निरसने । २१० श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च । २११ पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ इति धातुपाठान्तर्गणसूत्राणि ॥

उणादिसूत्रान्तर्गणसूत्राणि ।

२१२ कोकतेर्वा कुक्च । २१३ कमेर्बुक् च । २१४ लङ्केर्वृद्धिश्च । २१५ कुन्तिकशिकौतिभ्यः प्रत्ययस्य मुट् च । २१६ चरेर्नुम् च । २१७ शमेर्बुक् च । २१८ लङ्केर्वृद्धिश्च । २१९ तमेर्बुग्वृद्धिश्च । २२० शृणातेर्दुग्वृद्धिश्च । २२१ दुक्रोः कुक्च । २२२ कौतेर्नुम्च ॥ इति उणादिसूत्रान्तर्गणसूत्राणि ॥

सौत्रधातवः ।

१ 'ऋतिः'	(३।१।२९)	११ 'पीयुः'	(३।७६ उ)
२ 'कञ्जिः'	(३।१३७ उ)	१२ 'भडः'	(१।५४ उ)
३ 'काडिः'	(४।८२ उ)	१३ 'युषः'	(१।९७ उ)
४ 'कदिः'	(४।८२उ)	१४ 'वर्णिः'	(४।१२३ उ)
५ 'क्षदिः'	(२।९२ उ)	१५ 'सातिः'	(३।१।१३८)
६ 'जुः'	(३।२।१५०)	१६ 'स्कम्भुः'	(३।१।८२)
७ 'तदिः'	(४।६६ उ)	१७ 'स्कुम्भुः'	(३।१।८२)
८ 'तव'	(१।४८ उ)	१८ 'स्तम्भुः'	(३।१।८२)
९ 'तुः'	(७।३।९५)	१९ 'स्तुम्भुः'	(३।१।८२)
१० 'दभिः'	० (वा)	२० 'शुः'	(२।२५ उ)

(१) अष्टाध्यायीसूत्रपाठसूची ।

३९०७ कपि पूर्वम् ६।२।१७३
१११० कपिबोधादाङ्गिरसे ४।१।१०७
३०८४ कपिष्ठलो गोत्रे ८।३।९१
२३१० कमेर्णिङ् ३।१।३०
१६६३ कम्बलाच्च संज्ञायाम् ५।१।३
११९४ कम्बोजाल्लुक् ४।१।१७५
३२९३ करणाधिकरणयोश्च ३।३।११७
६०४ करणे च स्तोकाल्प० २।३।३३
२९९६ करणे यजः ३।२।८५
३२५९ करणेऽयोविद्रुषु ३।३।८२
३३५८ करणे हनः ३।४।३७
२०६५ कर्कलोहितादीकक् ५।३।११०
१४४४ कर्णललाटात्कनलं० ४।३।६५
१०३६ कर्णे लक्षणस्यावि० ६।३।११५
३८४६ कर्णो वर्णलक्षणात् ६।२।११२
२६८० कर्तरि कर्मव्यतिहारे १।३।१४
२८३२ कर्तरि कृत् ३।४।६७
७१० कर्तरि च २।२।१६
३१६७ कर्तरि चर्षिदेवतयोः ३।२।१८६
२९७४ कर्तरि भुवः खिष्णुच्० ३।२।५७
२१६७ कर्तरि शप् ३।१।६८
२९८९ कर्तर्युपमाने ३।२।७९
२६६५ कर्तुः क्यङ् सलोपश्च ३।१।११
५३५ कर्तुरीप्सिततमं कर्म १।४।७९
५६१ कर्तृकरणयोस्तृतीया २।३।१८
६९४ कर्तृकरणे कृता बहु० २।१।३२
६२३ कर्तृकर्मणोः कृति २।३।६५
३३०८ कर्तृकर्मणोश्च भूकृ० ३।३।१२७
२७१० कर्तृस्थे चाशरीरे क० १।३।३७
३३६४ कर्त्रोर्जीवपुरुषयोर्न० ३।४।४३
१७६७ कर्मण उकञ् ५।१।१०३
५६९ कर्मणा यमभिप्रैति० १।४।३२
१८३६ कर्मणि घटोऽठच् ५।२।३५
७०८ कर्मणि च २।२।१४
३२९१ कर्मणि च येन सं० ३।३।११६
३३५० कर्मणि दृशिविदोः० ३।४।२९
५३७ कर्मणि द्वितीया २।३।२
२९३६ कर्मणि भृतौ ३।२।२२
२९९७ कर्मणि हनः ३।२।८६
३००३ कर्मणीनिविक्रियः ३।२।९३
२६७१ कर्मणो रोमन्थतपो० ३।१।१५
३००२ कर्मण्यग्न्याख्यायाम् ३।२।९२
२९१३ कर्मण्यण् ३।२।१
३२७१ कर्मण्यधिकरणे च ३।३।९३
३३४६ कर्मण्याक्रोशे कृ० ३।४।२५
२१४६ कर्मधारयवदुत्तरेषु ८।१।११
३७८० कर्मधारयेऽनिष्ठा ६।२।४६
१४९१ कर्मन्दकृशाश्वादि० ४।३।१११
५४८ कर्मप्रवचनीययुक्ते० २।३।८
५४६ कर्मप्रवचनीयाः १।४।८३
२७६६ कर्मवत्कर्मणा तुल्य० ३।१।८७
१७६४ कर्मवेषाद्यत् ५।१।१००
३२१५ कर्मव्यतिहारे ण० ३।३।४३
१६१४ कर्माध्ययने वृत्तम् ४।४।६३
३६८० कर्षात्वतो घ० ६।१।१५९
१४८८ कलापिनोऽण् ४।३।१०८
१४८४ कलापिवैशम्पाय० ४।३।१०४
१४२३ कलाप्यश्वत्थयवबुसा० ४।३।४८
१२०९ कलेर्ढक् ४।२।८ (वा २६८८)
११३१ कल्याण्यादीनामि० ४।१।१२६
१०३३ कवं चोष्णे ६।३।१०७
३५९२ कव्यध्वरपृतनस्यर्चि० ७।४।३९
३४११ कव्यपुरीषपुरीष्येषु० ३।२।६५
३३६७ कषादिषु यथाविध्य० ३।४।४६
२६७० कष्टाय क्रमणे ३।१।१४
१४४ कस्कादिषु च ८।३।४८
२०२७ कस्य च दः ५।३।७२
१२२७ कस्येत् ४।२।२५
१९१८ काण्डाण्डादीरन्नीर० ५।२।१११
४८१ काण्डान्तात्क्षेत्रे ४।१।२३

२९१९ तुन्दशोकयोः परिमृ० ३।२।५
१९२४ तुन्दादिभ्य इलच ५।२।११७
१९४५ तुन्दिवलिवटेर्भः ५।२।१३९
३९४६ तुपश्यपश्यताहैः पू० ८।१।३९
३९४ तुभ्यमह्यौ ङयि ७।२।९५
५८२ तुमर्थाच्च भाववचनात् २।३।१५
३४३६ तुमर्थे सेसेनसेऽसे० ३।४।९
३१७५ तुमुण्वुलौ क्रियायां०३।३।१०
२००८ तुरिष्ठेमेयःसु ६।४।१५४
२४४४ तुरुस्तुशम्यमः सा० ७।३।९५
६३० तुल्यार्थैरतुलोप० २।३।७२
१० तुल्यास्यप्रयत्नं स० १।१।९
२००७ तुश्छन्दसि ५।३।५९
२१९७ तुह्योस्तातङ्ङाशि० ७।१।३५
१४७४ तूदीशलातुरवर्मती० ४।३।९४
३३८९ तूष्णीमि भुवः ३।४।६३
७०९ तृजकाभ्यां कर्तरि २।२।१५
२७४ तृज्वत्क्रोष्टुः ७।१।९५
२५४५ तृणह इम् ७।३।९२
१०२९ तृणे च जातौ ६।३।१०३
३७८२ तृतीया कर्मणि ६।२।४८
३३९४ तृतीया च होश्छन्दसि २।३।३
६९२ तृतीया तत्कृतार्थेन० २।१।३०
३२१ तृतीयादिषु भाषित० ७।१।७४
७८४ तृतीयाप्रभृतीन्यन्य० २।२।२१
५४९ तृतीयार्थे १।४।८५
६५८ तृतीयासप्तम्योर्बहुलम् २।४।८४
२२३ तृतीयासमासे १।१।३०
३११५ तृन् ३।२।१३५
३३२६ तृषिमृषिकृषेः काश्य० १।२।२५
२३०१ तृफलभजत्रपश्च ६।४।१२२
११९२ ते तद्राजाः ४।१।१७४
१७०२ तेन क्रीतम् ५।१।३७
१७७८ तेन तुल्यं क्रिया चे० ५।१।११५
१५५० तेन दीव्यति खनति ४।४।२
१२८० तेन निर्वृत्तम् ४।२।६८
१७४३ तेन निर्वृत्तम् ५।१।७९
१७५७ तेन परिजय्यलभ्य० ५।१।९३
१४८१ तेन प्रोक्तम् ४।३।१०१
१७६२ तेन यथाकथाचहस्ता० ५।१।९८
१२०२ तेन रक्तं रागात् ४।२।१
१८२७ तेन वित्तश्चुञ्चुप्चणपौ ५।२।२६
८४८ तेन सहेति तुल्ययोगे २।२।२८
१४९२ तेनैकदिक् ४।३।११२
२२३८ ते प्राग्धातोः १।४।८०
४०६ तेमयावेकवचनस्य ८।१।२२
११५ तोः षि ८।४।४३
११७ तोर्लि ८।४।६०
३१०६ तौ सत् ३।२।१२७
४२९ त्यदादिषु दृशेरना० ३।२।६०
२६५ त्यदादीनामः ७।२।१०२
१३३६ त्यदादीनि च १।१।७४
९३८ त्यदादीनि सर्वैर्नित्यम् १।२।७२
३७०४ त्यागरागहासकुह० ६।१।२१६
१५१८ त्रपुजतुनोः षुक् ४।३।१३८
३१२० त्रसिगृधिधृषिक्षि० ३।२।१४०
१७२७ त्रिंशच्चत्वारिंशतो० ५।१।६२
८८५ त्रिककुत्पर्वते ५।४।१४७
२९८ त्रिचतुरोः स्त्रियां० ७।२।९९
५६ त्रिप्रभृतिषु शाकटा० ८।४।५०
१८५५ त्रेः संप्रसारणं च ५।२।५५
१५७० त्रेर्मम्नित्यम् ४।४।२०
८०९ त्रेस्त्रयः ६।३।४८
२६४ त्रेस्त्रयः ७।१।५३
३८९ त्वमावेकवचने ७।२।९७
४०७ त्वामौ द्वितीयायाः ८।१।२३
३८४ त्वाहौ सौ ७।२।९४
१००२ त्वे च ६।३।६४
३४९७ थट् च च्छन्दसि ५।२।५०
२२६१ थलि च सेटि ६।४।१२१

२५९८ शतेरगतौ तः ७।३।४२
४४६ शप्श्यनोर्नित्यम् ७।१।८१
१५८४ शब्ददर्दुरं करोति ४।४।३४
२६७३ शब्दवैरकलहाभ्र० ३।१।१७
२५१९ शमामष्टानां दीर्घः० ७।३।७४
३५४३ शमिता यज्ञे ६।४।५४
३१२१ शमित्यष्टाभ्यो घिनुण् ३।२।१४१
२९२८ शमि धातोः संज्ञायाम् ३।२।१४
१५२२ शम्याः ष्लञ् ४।३।१४२
९७६ शयवासवासिष्वका० ६।३।१८
११०४ शरद्वच्छुनकदर्भा० ४।१।१०२
१०४२ शरादीनां च ६।३।१२०
१४३० शरीरावयवाच्च ४।३।५५
१६६६ शरीरावयवाद्यत् ५।१।६
३४० शरोऽचि ८।४।४९
२०६२ शर्करादिभ्योऽण् ५।३।१०७
१३०२ शर्कराया वा ४।२।८३
१५० शर्परे विसर्जनीयः ८।३।३५
२२५९ शर्पूर्वाः खयः ७।४।६१
२३३६ शल इगुपधादनिटः० ३।१।४५
१६०४ शलालुनोऽन्यतरस्याम् ४।४।५४
१२० शश्छोऽटि ८।४।६३
३९१ शसो न ७।१।२९
१५०८ शाकलाद्वा ४।३।१२८
२०५८ शाखादिभ्यो यत् ५।३।१०३
२५८५ शाच्छासाह्वाव्यावे० ७।३।३७
३०७५ शाच्छोरन्यतरस्याम् ७।४।४१
१७०० शाणाद्वा ५।१।३५
११२ शात् ८।४।४४
३७४३ शारदेऽनार्तवे ६।२।९
५२७ शार्ङ्गरवाद्यञो ङीन् ४।१।७३
१८२१ शालीनकौपीने अ० ५।२।२०
२४८६ शास इदङ्हलोः ६।४।३४
२४१० शासिवसिघसीनां० ८।३।६०
२५८७ शा हौ ६।४।३५

१३०८ शिखाया वलच् ४।२।८९
१२३ शि तुक् ८।३।३१
३८७२ शितेर्नित्याबह्वज्ब० ६।२।१३८
२०५७ शिलाया ढः ५।३।१०२
१६०५ शिल्पम् ४।४।५५
३८१० शिल्पिनि चाकृञः ६।२।७६
२९०७ शिल्पिनि ष्वुन् ३।१।१४५
३४८९ शिवशमरिष्टस्य करे ४।४।१४३
१११९ शिवादिभ्योऽण् ४।१।११२
१४६८ शिशुक्रन्दयमसभ० ४।३।८८
३१३ शि सर्वनामस्थानम् १।१।४२
२४४१ शीङः सार्वधातुके० ७।४।२१
२४४२ शीङो रुट् ७।१।६
१८७२ शीतोष्णाभ्यां कारिणि ५।२।७२
३५१४ शीर्षश्छन्दसि ६।१।६०
१७३० शीर्षच्छेदाद्यच्च ५।१।६५
१६११ शीलम् ४।४।६१
१२२८ शुक्राद्घन् ४।२।२६
१४५५ शुण्डिकादिभ्योऽण् ४।३।७६
११२६ शुभ्रादिभ्यश्च ४।१।१२३
३०३० शुषः कः ८।२।५१
३३५६ शुष्कचूर्णरूक्षेषु पिषः ३।४।३५
३६९४ शुष्कधृष्टौ ६।१।२०६
९१४ शूद्राणामनिरवसि० २।४।१०
१६९१ शूर्पादन्यतरस्याम् ५।१।२६
२१३६ शूलात्पाके ५।४।६५
१२१८ शूलोखाद्यत् ४।२।१७
१८७९ शृङ्खलमस्य बन्ध० ५।२।७९
३८४९ शृङ्गमवस्थायां च ६।२।११५
३०६७ शृतं पाके ३।१।२७
२४९५ शॄदॄपां ह्रस्वो वा ७।४।१२
३१५३ शॄवन्द्योरारुः ३।२।१७३
१०२ शे १।१।१३
२५४२ शे मुचादीनाम् ७।१।५९
२०३८ शेवलसुपरिविशाल० ५।३।८४

गणसूत्रसूची ।

---

(३) धातुपाठसूची ।

७९२ अक	(भ्वा.	प.	से.)	१४६ अगि	(भ्वा.	प.	से.)
८७ अकि	(भ्वा.	आ.	से.)	१०९ अघि	(भ्वा.	आ.	से.)
६९४ अक्षू	(भ्वा.	प.	से.)	१९२८ अङ्क	(चु.	उ.	से.)
७९३ अग	(भ्वा.	प.	से.)	१९२९ अङ्ग	(चु.	उ.	से.)

८६२	अचि (पा.)	(भ्वा.	उ.	से.)
८६२	अचु (पा.)	(भ्वा.	उ.	से.)
२३०	अज	(भ्वा.	प.	से.)
१७८६	अजि	(चु.	उ.	से.)
२९५	अट	(भ्वा.	प.	से.)
२५४	अट्ट	(भ्वा.	आ.	से.)
१५६२	अट्ट	(चु.	प.	से.)
२६१	अठि	(भ्वा.	आ.	से.)
३५८	अड	(भ्वा.	प.	से.)
३४८	अड्ड	(भ्वा.	प.	से.)
४४४	अण	(भ्वा.	प.	से.)
११७६	अण	(दि.	आ.	से.)
३८	अत	(भ्वा.	प.	से.)
६१	अति	(भ्वा.	प.	से.)
१०११	अद	(अ.	प.	से.)
६२	अदि	(भ्वा.	प.	से.)
१०७०	अन	(अ.	प.	से.)
११७६	अन (पा.)	(दि.	आ.	से.)
१८८	अन्तु	(भ्वा.	प.	से.)
८६२	अन्चु	(भ्वा.	उ.	से.)
१७३९	अन्चु	(चु.	उ.	से.)
१४५९	अन्जू	(रु.	प.	से.)
१९२६	अन्ध	(चु	उ.	से.)
३७८	अबि	(भ्वा.	आ.	से.)
५५६	अभ्र	(भ्वा.	प.	से.)
३८९	अभि (पा.)	(भ्वा.	आ.	से.)
३८९	अभी (पा.)	(भ्वा.	आ.	से.)
४६५	अम	(भ्वा.	प.	से.)
१७२१	अम	(चु.	उ.	से.)
४७४	अय	(भ्वा.	आ.	से.)
१६४४	अर्क	(चु.	प.	से.)
२०४	अर्च	(भ्वा.	प.	से.)
१८०९	अर्च	(चु.	उ.	से.)
२२४	अर्ज	(भ्वा.	प.	से.)
१७२६	अर्ज	(चु.	उ.	से.)
१९०६	अर्थ	(चु.	आ.	से.)
५५	अर्द	(भ्वा.	प.	से.)
१८२९	अर्द	(चु.	उ.	से.)
४१५	अर्ब	(भ्वा.	प.	से.)
५८४	अर्व	(भ्वा.	प.	से.)
७४०	अर्ह	(भ्वा.	प.	से.)
१७३२	अर्ह	(चु.	उ.	से.)
१८३१	अर्ह	(चु.	उ.	से.)
५१५	अल	(भ्वा.	प.	से.)
६००	अव	(भ्वा.	प.	से.)
१५२४	अश	(क्र्या.	प.	से.)
१२६५	अशू	(स्वा.	आ.	से.)
८८६	अष (पा.)	(भ्वा.	उ.	से.)
८८६	अस	(भ्वा.	उ.	से.)
१०६५	अस	(अ.	प.	से.)
१९१९	अंस	(चु.	उ.	से.)
१२१०	असु	(दि.	प.	से.)
१२७३	अह	(स्वा.	प.	से.)
६३५	अहि	(भ्वा.	आ.	से.)
१७९८	अहि	(चु.	उ.	से.)
१७२८	आङः क्रन्द	(चु.	उ.	से.)
२०९	आछि	(भ्वा.	प.	से.)
१२६१	आप्लृ	(स्वा.	प.	अ.)
१८४०	आप्लृ	(चु.	उ.	अ.)
१०२१	आस	(अ.	आ.	अ.)
१०४७	इक्	(अ.	प.	अ.)
१४०	इख	(भ्वा.	प.	से.)
१४१	इखि	(भ्वा.	प.	से.)
१५३	इगि	(भ्वा.	प.	से.)
१०४६	इङ्	(अ.	आ.	अ)
३१८	इट	(भ्वा.	प.	से.)
१०४५	इण्	(अ.	प.	अ.)
६३	इदि	(भ्वा.	प.	से.)
१४४९	(ञि) इन्धी	(रु.	आ.	से.)
१३५८	इल	(तु.	प.	से.)

१६६१	इल	(चु.	प.	से.)
५८७	इवि	(भ्वा.	प.	से.)
११२७	इष	(दि.	प.	से.)
१३५२	इष	(तु.	प.	से.)
१५२६	इष	(क्र्या.	प.	से.)
६१०	ईक्ष	(भ्वा.	आ.	से.)
१४२	ईखि	(भ्वा.	प.	से.)
११४३	ईङ्	(दि.	आ.	अ.)
१८२	ईज	(भ्वा.	आ.	से.)
१०१९	ईड	(अ.	आ.	से.)
१६६८	ईड	(चु.	प.	से.)
१०१८	ईर	(अ.	आ.	से.)
१८११	ईर	(चु.	उ.	से.)
५१०	ईर्क्ष्य	(भ्वा.	प.	से.)
५११	ईर्ष्य	(भ्वा.	प.	से.)
१०२०	ईश	(अ.	आ.	से.)
६११	ईष	(भ्वा.	प.	से.)
६८४	ईष	(भ्वा.	प.	से.)
६३२	ईह	(भ्वा.	आ.	से.)
६५७	उक्ष	(भ्वा.	प.	से.)
१२८	उख	(भ्वा.	प.	से.)
१२९	उखि	(भ्वा.	प.	से.)
९५३	उङ्	(भ्वा.	आ.	अ.)
१२२४	उच	(दि.	प.	से.)
२१५	उछि	(भ्वा.	प.	से.)
१२९५	उछि	(तु.	प.	से.)
२१६	उछी	(भ्वा.	प.	से.)
१२९६	उछी	(तु.	प.	से.)
१३०९	उज्झ	(तु.	प.	से.)
३३८	उठ	(भ्वा.	प.	से.)
१४५८	उन्दी	(रु.	प.	से.)
१३२१	उन्भ	(तु.	प.	से.)
१३०४	उब्ज	(तु.	प.	से.)
१३२०	उभ	(तु.	प.	से.)
२०	उर्द	(भ्वा.	आ.	से.)

५६९	उर्वी	(भ्वा.	प.	से.)
६९६	उष	(भ्वा.	प.	से.)
७३९	उहिर्	(भ्वा.	प.	से.)
३३८	ऊठ (पा.)	(भ्वा.	प.	से.)
१८८९	ऊन	(चु.	उ.	से.)
४८३	ऊयी	(भ्वा.	आ.	से.)
१५५०	ऊर्ज	(चु.	प.	से.)
१०३९	ऊर्णुञ्	(अ.	उ.	से.)
६८३	ऊष	(भ्वा.	प.	से.)
६४८	ऊह	(भ्वा.	आ.	से.)
९३६	ऋ	(भ्वा.	प.	अ.)
१०९८	ऋ	(जु.	प.	अ.)
१३०२	ऋच	(तु.	प.	अ.)
१२९७	ऋछ	(तु.	प.	अ.)
१७६	ऋज	(भ्वा.	आ.	अ.)
१७७	ऋजि	(भ्वा.	आ.	अ.)
१४६८	ऋण	(त.	उ.	अ.)
१२४६	ऋधु	(दि.	प.	अ.)
१२७२	ऋधु	(स्वा.	प.	अ.)
१३१७	ऋम्फ	(तु.	प.	अ.)
१३१६	ऋफ	(तु.	प.	अ.)
१२८८	ऋषी	(तु.	प.	अ.)
१४९८	ॠ	(क्र्या.	प.	अ.)
१७९	एजृ	(भ्वा.	आ.	अ.)
२३४	एजृ	(भ्वा.	प.	अ.)
२६७	एठ	(भ्वा.	आ.	अ.)
२	एध	(भ्वा.	आ.	अ.)
६१८	एषृ	(भ्वा.	आ.	अ.)
१२१	ओखृ	(भ्वा.	प.	अ.)
४५४	ओणृ	(भ्वा.	प.	अ.)
१०१०	(टु) ओश्वि	(भ्वा.	प.	अ.)
९०	कक	(भ्वा.	आ.	अ.)
९४	ककि	(भ्वा.	आ.	अ.)
१२०	कख	(भ्वा.	प.	से.)
७८४	कखे	(भ्वा.	प.	से.)

७९१ कगे	(भ्वा. प. से.)	४९८ कल्ल	(भ्वा. आ. से.)
१६८ कच	(भ्वा. आ. से.)	३८० कवृ	(भ्वा. आ. से.)
१६९ कचि	(भ्वा. आ. से.)	१०२४ कश (पा.)	(अ. आ. से.)
३२० कटी	(भ्वा. प. से.)	६८९ कष	(भ्वा. प. से.)
२९४ कटे	(भ्वा. प. से.)	८६० कस	(भ्वा. प. से.)
३३३ कठ	(भ्वा. प. से.)	१०२४ कस (पा.)	(अ. आ. से.)
२६४ कठि	(भ्वा. आ. से.)	१०२४ कसि	(अ. आ. से.)
१८४८ कठि	(चु. उ. से.)	६६७ काक्षि	(भ्वा. प. से.)
३६० कड	(भ्वा. प. से.)	१७० काचि	(भ्वा. आ. से.)
१३८१ कड	(तु. प. से.)	१८८१ काल (पा.)	(चु. उ. से.)
३४९ कड्ड	(भ्वा. प. से.)	६४७ काशृ	(भ्वा. आ. से.)
२८२ कडि	(भ्वा. आ. से.)	११६२ काशृ	(दि. आ. से.)
३६० कडि (पा.)	(भ्वा. प. से.)	६२३ कासृ	(भ्वा. आ. से.)
१५८३ कडि	(चु. प. से.)	११०१ कि	(जु. प. अ.)
४४९ कण	(भ्वा. प. से.)	३०१ किट	(भ्वा. प. से.)
७९४ कण	(भ्वा. प. से.)	३१९ किट	(भ्वा. प. से.)
१६८९ कण	(चु. उ. से.)	९९३ कित	(भ्वा. प. से.)
१७१६ कण	(चु. प. से.)	१३५४ किल	(तु. प. से.)
३७ कत्थ	(भ्वा. आ. से.)	१६४१ कीट	(चु. प. से.)
१९१६ कत्र	(चु. उ. से.)	५२४ कील	(भ्वा. प. से.)
१८९२ कथ	(चु. उ. से.)	१०४२ कु	(अ. प. अ.)
७० कदि	(भ्वा प. से.)	९१ कुक	(भ्वा. आ. से.)
७७२ कदि	(भ्वा. आ. से.)	९९१ कुङ्	(भ्वा. आ. अ.)
४६० कनी	(भ्वा. प. से.)	१४०२ कुङ	(तु. आ. अ.)
३७९ कपि	(भ्वा. आ. से.)	१८४ कुच	(भ्वा. प. से.)
४४३ कमु	(भ्वा. आ. से.)	८५७ कुच	(भ्वा. प. से.)
२२८ कर्ज	(भ्वा. प. से.)	१३६९ कुच	(तु. प. से.)
१९२९ कर्ण (पा.)	(चु. उ. से.)	१९९ कुञ्ज	(भ्वा. प. से.)
१९१६ कर्त (पा.)	(चु. उ. से.)	१३६७ कुट	(तु. प. से.)
५९ कर्द	(भ्वा. प. से.)	१६९९ कुट (पा.)	(चु. आ. से.)
४२० कर्ब	(भ्वा. प. से.)	१५५९ कुट्ट	(चु. प. से.)
५८१ कर्व	(भ्वा. प. से.)	१७०३ कुट्ट	(चु. आ. से.)
४९७ कल	(भ्वा. आ. से.)	३४२ कुठि	(भ्वा. प. से.)
१६०५ कल	(चु. प. से.)	१५८५ कुठि (पा.)	(चु. प. से.)
१६६६ कल	(चु. उ. से.)	१३८४ कुड	(तु. प. से.)

३२२ कुडि	(भ्वा.	प.	से.)
१५८४ कुडि	(चु.	प.	से.)
२७० कुडि	(भ्वा.	आ.	से.)
१३३६ कुण	(तु.	प.	से.)
१८९४ कुण	(चु.	उ.	से.)
१८९७ कुण	(चु.	उ.	से.)
१५४० कुद्रि	(चु.	प.	से.)
१६९८ कुत्स	(चु.	आ.	से.)
११३८ कुथ	(दि.	प.	से.)
१५१५ कुथ (पा.)	(क्र्या.	प.	से.)
४३ कुथि	(भ्वा.	प.	से.)
१८५ कुन्च	(भ्वा.	प.	से.)
१५१५ कुन्थ	(क्र्या.	प.	से.)
१२३४ कुप	(दि.	प.	से.)
१७८० कुप	(चु.	उ.	से.)
४२६ कुबि	(भ्वा.	प.	से.)
१६५६ कुबि	(चु.	प.	से.)
१६५६ कुभि (पा.)	(चु.	प.	से.)
१८७८ कुमार	(चु.	उ.	से.)
१३४२ कुर	(तु.	प.	से.)
२१ कुर्द	(भ्वा.	आ.	से.)
८४२ कुल	(भ्वा.	प.	से.)
१७६६ कुशि	(चु.	उ.	से.)
१५१९ कुष	(क्र्या.	प.	से.)
१२१९ कुस	(दि.	प.	से.)
१७६४ कुसि	(चु.	उ.	से.)
१७१२ कुस्म	(चु.	आ.	से.)
१९०२ कुह	(चु.	आ.	से.)
२२३ कूज	(भ्वा.	प.	से.)
१७०२ कूट	(चु.	आ.	से.)
१८९१ कूट	(चु.	उ.	से.)
५२५ कूल	(भ्वा.	प.	से.)
१२५४ कृञ्	(स्वा.	उ.	अ.)
१४७२ (डु) कृञ्	(त.	उ.	अ.)
१३८३ कृड	(तु.	प.	से.)

१४३६ कृती	(तु.	प.	से.)
१४४८ कृती	(रु.	प.	से.)
१८७० कृप	(चु.	उ.	से.)
७६२ कृपू	(भ्वा.	आ.	से.)
१७४९ कृप्	(चु.	उ.	से.)
५९८ कृवि	(भ्वा.	प.	से.)
१२२८ कृश	(दि.	प.	से.)
९९० कृष	(भ्वा.	प.	अ.)
१२८७ कृष	(तु.	उ.	अ.)
१४१० कॄ	(तु.	प.	से.)
१४९७ कॄ	(क्र्या.	प.	से.)
१४८६ कॄञ्	(क्र्या.	उ.	से.)
१६९४ कॄत	(चु.	प.	से.)
१८९६ केत	(चु.	आ.	से.)
३६८ केपृ	(भ्वा.	आ.	से.)
५३७ केलृ	(भ्वा.	प.	से.)
५१६ कै	(भ्वा.	प.	से.)
१११२ क्नसु	(दि.	प.	से.)
१४८१ क्नूञ्	(क्र्या.	उ.	से.)
४८५ क्नूयी	(भ्वा.	आ.	से.)
५५५ क्मर	(भ्वा.	प.	से.)
८०१ क्रथ	(भ्वा.	प.	से.)
७७२ क्रद (पा.)	(भ्वा.	आ.	से.)
७१ क्रदि	(भ्वा.	प.	से.)
७७३ क्रदि	(भ्वा.	आ.	से.)
७६१ क्रप	(भ्वा.	आ	से.)
४७३ क्रमु	(भ्वा.	प.	से.)
१४७४ (डु) क्रीञ्	(क्र्या.	उ.	से.)
३५० क्रीडृ	(भ्वा.	प.	से.)
१३९५ क्रुड	(तु.	प.	से.)
११९० क्रुध	(दि.	प.	अ.)
१८६ क्रुन्च	(भ्वा.	प.	से.)
८५६ क्रुश	(भ्वा.	प.	से.)
८०२ क्लथ	(भ्वा.	प.	से.)
७७३ क्लद (पा)	(भ्वा.	आ.	से.)

७२ क्लदि (भ्वा. प. से.)
७४ क्लदि (भ्वा. आ. से.)
१६५९ क्लप (पा.) (चु. प. से.)
१२०८ क्लमु (दि. प. से.)
१९ क्लिदि (भ्वा. आ. से.)
७३ क्लिदि (भ्वा. प. से.)
१२४३ क्लिद (दि. प. से.)
११६१ क्लिश (दि. आ. से.)
१५२३ क्लिशू (क्र्या. प. से.)
३८१ क्लीबृ (भ्वा. आ. से.)
९५८ क्लुङ् (पा.) (भ्वा. आ. अ.)
६०७ क्लेश (भ्वा. आ. से.)
५०३ क्लेवृ (पा.) (भ्वा. आ. से.)
४५० क्वण (भ्वा. प. से.)
८४६ क्वथे (भ्वा. प. से.)
७६९ क्षजि (भ्वा. आ. से.)
१४६६ क्षणु (त. उ. से.)
१९४२ क्षप (चु. उ. से.)
८१६ क्षपिः (पा.) (भ्वा. प. से.)
१६२१ क्षपि (चु. प. से)
१२०७ क्षमू (दि. प. अ.)
४४२ क्षमूष् (भ्वा. आ. से.)
८५१ क्षर (भ्वा. प. से.)
१५९८ क्षल (चु. प. से.)
२३६ क्षि (भ्वा. प. अ.)
१२७७ क्षि (स्वा. प. अ.)
१४०८ क्षि (तु. प. अ.)
१४६७ क्षिणु (त. उ. से.)
११२१ क्षिप (दि. प. अ.)
१२८६ क्षिप (तु. उ. अ.)
२३७ क्षीज (भ्वा. प. से.)
३८२ क्षीबृ (भ्वा. आ. से.)
५६७ क्षीवु (भ्वा. प. से.)
१५०७ क्षीष् (क्र्या. प. से.)
१४५४ क्षुदिर (रु. उ. अ.)

१०३६ (टु) क्षु (अ. प. से.)
११९१ क्षुध (दि. प. अ.)
७५१ क्षुभ (भ्वा. आ. से.)
१२४० क्षुभ (दि. प. से.)
१५२० क्षुभ (क्र्या. प. से.)
१३४९ क्षुर (तु. प. से.)
५६८ क्षेवु (भ्वा. प. से.)
९१३ क्षै (भ्वा. प. से.)
१८७६ क्षोट (चु. उ. से.)
१०३७ क्ष्णु (अ. प. से.)
४८६ क्ष्मायी (भ्वा. आ. से.)
५२० क्ष्मील (भ्वा. प. से.)
७४४ (ञि) क्ष्विदा (पा.) (भ्वा. आ. से.)
१२४९ (ञि) क्ष्विदा (दि. प. से.)
५३९ क्ष्वेल (भ्वा. प. से.)
१५३२ खच (क्र्या. प. से.)
२२२ खज (भ्वा. प. से.)
२२३ खजि (भ्वा. प. से.)
३०९ खट (भ्वा. प. से.)
१६३३ खट्ट (चु. प. से.)
१५८१ खड (चु. प. से.)
२८३ खडि (भ्वा. आ. से.)
१५८२ खडि (चु. प. से.)
५० खद (भ्वा. प. से.)
८७८ खनु (भ्वा. उ. से.)
२२९ खर्ज (भ्वा. प. से.)
६० खर्द (भ्वा. प. से.)
४२१ खर्ब (भ्वा. प. से.)
५८२ खर्व (भ्वा. प. से.)
१५३२ खव (पा.) (क्र्या. प. से.)
५४९ खल (भ्वा. प. से.)
६८६ खष (भ्वा. प. से.)
४९ खादृ (भ्वा. प. से.)
३०२ खिट (भ्वा. प. से.)
११७१ खिद (दि. आ. अ.)

१४३७ खिद	(तु.	प.	से.)
१४५० खिद	(रु.	आ.	अ.)
९५४ खुङ् (पा.)	(भ्वा.	अ.	आ.)
२०० खुजु	(भ्वा.	प.	से.)
१३८९ खुड (पा.)	(तु.	प.	से.)
१५८६ खुडि	(चु.	प.	से.)
१३४३ खुर	(तु.	प.	से.)
२२ खुर्द	(भ्वा.	आ.	से.)
१८७५ खेट	(चु.	उ.	से.)
५३८ खेल	(भ्वा.	उ.	से.)
५०६ खेवृ (पा.)	(भ्वा.	आ.	से.)
९१२ खै	(भ्वा.	प.	अ.)
१८७५ खोट (पा.)	(चु.	उ.	से.)
५५२ खोर्ऋ	(भ्वा.	प.	से.)
५५१ खोल	(भ्वा.	प.	से.)
२०६० ख्या	(अ.	प.	अ.)
२४६ गज	(भ्वा.	प.	से.)
१६४८ गज	(चु.	प.	से.)
२४७ गजि	(भ्वा.	प.	से.)
७७७ गड	(भ्वा.	प.	से.)
६५ गडि	(भ्वा.	प.	से.)
३६१ गडि	(भ्वा.	प.	से.)
१८५४ गण	(चु.	प.	से.)
१८८३ गति (पा.)	(चु.	उ.	से.)
५२ गद	(भ्वा.	प.	से.)
१८६१ गदी	(चु.	उ.	से.)
१६८९ गन्ध	(चु.	आ.	से.)
९८२ गम्लृ	(भ्वा.	प.	अ.)
२२६ गर्ज	(भ्वा.	प.	से.)
१६६५ गर्ज (पा.)	(चु.	प.	से.)
५७ गर्द	(भ्वा.	प.	से.)
१६६५ गर्द (पा.)	(चु.	प.	से.)
१६६५ गर्ध (पा.)	(चु.	प.	से.)
४२२ गर्ब	(भ्वा.	प.	से.)
५८३ गर्व	(भ्वा.	प.	से.)
१९०८ गर्व	(चु.	आ.	से.)
६३६ गर्ह	(भ्वा.	आ.	से.)
१८४६ गर्ह	(चु.	उ.	से.)
५४६ गल	(भ्वा.	प.	से.)
१७०० गल	(चु.	आ.	से.)
३९२ गल्भ	(भ्वा.	आ.	से.)
६३७ गल्ह	(भ्वा.	आ.	से.)
१८८४ गवेष	(चु.	उ.	से.)
११०६ गा	(जु.	प.	अ.)
९५० गाङ्	(भ्वा.	आ.	अ.)
४ गाधृ	(भ्वा.	आ.	से.)
६४९ गाहू	(भ्वा.	आ.	से.)
१४०० गु	(तु.	प.	अ.)
९४९ गुङ्	(भ्वा.	आ.	अ.)
१३७० गुज	(तु.	प.	से.)
२०३ गुजि	(भ्वा.	प.	से.)
१५८९ गुठि (पा.)	(चु.	प.	से.)
१३७१ गुड	(तु.	प.	से.)
१५८५ गुडि	(चु.	प.	से.)
१८९५ गुण	(चु.	उ.	से.)
२४ गुद	(भ्वा.	आ.	से.)
११२० गुध	(दि.	प.	से.)
१५१८ गुध	(क्र्या.	प.	से.)
१३१९ गुन्फ	(तु.	प.	से.)
९७० गुप	(भ्वा.	आ.	से.)
१२३५ गुप	(दि.	प.	से.)
१७७२ गुप	(चु.	उ.	से.)
३९५ गुपू	(भ्वा.	प.	से.)
१३१८ गुफ	(तु.	प.	से.)
१३९७ गुरी	(तु.	आ.	से.)
२३ गुर्द	(भ्वा.	आ.	से.)
१६६६ गुर्द	(चु.	प.	से.)
५७४ गुर्वी	(भ्वा.	प.	से.)
८९६ गुहू	(भ्वा.	उ.	से.)
१६९५ गूर	(चु.	आ.	से.)

२९४	चेट (पा.)	(भ्वा.	प.	से.)
२७८	चडि	(भ्वा.	आ.	से.)
७९६	चण	(भ्वा.	प.	से.)
८६९	चते	(भ्वा.	प.	से.)
६८	चादि	(भ्वा.	प.	से.)
८६६	चदे	(भ्वा.	उ.	से.)
१८४१	चन (पा)	(चु.	उ.	से.)
१९०	चन्चु	(भ्वा.	प.	से.)
३९९	चप	(भ्वा.	प.	से.)
१६२७	चप (पा)	(चु.	प.	से.)
१६२०	चर्पि	(चु.	प.	से.)
४६९	चमु	(भ्वा.	प.	से.)
१२७५	चमु	(स्वा.	प.	से.)
४७८	चय	(भ्वा.	आ.	से.)
५५९	चर	(भ्वा.	प.	से.)
१७४६	चर	(चु.	उ.	से.)
१०८१	चर्करीत	(अ.	आ.	से.)
७१७	चर्च	(भ्वा.	प.	से.)
१७१३	चर्च	(चु.	उ.	से.)
१३००	चर्च	(तु.	प.	से.)
४२५	चर्ब	(भ्वा.	प.	से.)
५७९	चर्व	(भ्वा.	प.	से.)
८३२	चल	(भ्वा.	प.	से.
१३५७	चल	(तु.	प.	से.)
१६०९	चल	(चु.	प.	से.)
८१२	चलिः	(भ्वा.	प.	से.
८८९	चष	(भ्वा.	उ.	से.)
७२९	चह	(भ्वा.	प.	से.)
१६२७	चह	(चु.	प.	से.)
१८६७	चह	(चु.	उ.	से.)
८८०	चायृ	(भ्वा.	उ.	से.)
१७९९	चि	(चु.	उ.	से.)
१६३०	चिञ्	(चु.	प.	से.)
१२५२	चिञ्	(स्वा.	उ.	अ.)
२१५	चिट	(भ्वा.	प.	से.)

१६७४	चित	(चु.	आ.	से.)
१५३६	चिति	(चु.	प.	से.)
३९	चिती	(भ्वा.	प.	से.)
१९१८	चित्र	(चु.	उ.	से.)
१२७८	चिरि	(स्वा.	प.	से.)
१३५६	चिल	(तु.	प.	से.)
५३३	चिल्ल	(भ्वा.	प.	से.)
१८२८	चीक	(चु.	उ.	से.)
३८४	चीभृ	(भ्वा	आ.	से.)
१७७५	चीव	(चु.	उ.	से.)
८७९	चीवृ	(भ्वा.	प.	से.)
१५९७	चुक्क	(चु.	प.	से.)
५१३	चुच्य (पा.)	(भ्वा.	प.	से.)
१६१४	चुट	(चु.	प.	से.)
१३७८	चुट	(तु.	प.	से.)
१५६१	चुट्ट	(चु.	प.	से.)
१६६०	चुटि	(चु.	प.	से.)
१३९२	चुड	(तु.	प.	स.)
३२५	चुडि	(भ्वा.	प.	से.)
३४७	चुड्ड	(भ्वा.	प.	से.)
१५९३	चुद	(चु.	प.	से.)
४०३	चुप	(भ्वा.	प.	से.)
४२९	चुबि	(भ्वा.	प.	से.)
१६३६	चुबि.	(चु.	प.	से.)
१५३५	चुर	(चु.	प.	से.)
११५८	चूरी	(दि.	आ.	से.)
१८३६	चुर्ब	(चु.	प.	से.)
१६०३	चुल	(चु.	प.	से.)
५३१	चुल्ल	(भ्वा.	प.	से.)
१५५३	चूर्ण	(चु.	प.	से.)
१६४२	चूर्ण	(चु.	प.	से.)
६७३	चूष	(भ्वा.	प.	से.)
१३२५	चृती	(तु.	प.	से.)
१८२१	चृप (पा.)	(चु.	प.	से.)
५३६	चेल	(भ्वा.	प.	से.)

२५६ चेट (भ्वा. आ. से.)
१७४७ च्यु (चु. उ. से.)
९५५ च्युङ् (भ्वा. आ. से.)
४० च्युतिर् (भ्वा. प. से.)
१६२२ छजि (चु. प. से.)
१८३४ छद (चु. उ. से.)
१९३६ छद (चु. उ. से.)
८१३ छदिर् (भ्वा. प. से.)
१५७८ छदि (चु. प. से.)
४७० छमु (भ्वा. प. से.)
१५९० छर्द (चु. प. से.)
८९० छष (भ्वा. उ. से.)
१४४१ छिदिर् (रु. उ. अ.)
१९२५ छिद्र (चु. उ. से.)
१३७९ छुट (तु. प. से.)
१३८९ छुड (पा.) (तु. प. से.)
१४१९ छुप (तु. प. अ.)
१३७३ छुर (तु. प. से.)
१८२१ छृप (पा.) (चु उ. से.)
१४४६ (उ) छृदिर् (रु. उ. से.)
१८२१ छृदी (चु. उ. से.)
१९३५ छेद (चु उ. से.)
११४६ छो (दि. प. अ.)
१०७१ जक्ष (अ. प. से.)
२४२ जज (भ्वा. प. से.)
२४३ जजि (भ्वा प. से.)
३०५ जट (भ्वा. प. से.)
११०५ जन (जु. अ. से.)
११४९ जनी (दि. आ. से.)
३९७ जप (भ्वा. प. से.)
१७१७ जभि (चु. उ. से.)
३८८ जभि (भ्वा. आ. से.)
४७१ जमु (भ्वा प. से.)
७१६ जर्ज (भ्वा. प. से.)
[illegible] जर्ज (तु. प. से.)

१५४४ जल (भ्वा. प. से.)
८३३ जल (चु. प. से.)
३९८ जल्प (भ्वा. प. से.)
६८८ जष (भ्वा. प. से.)
१६६७ जसि (चु. प. से.)
१६६९ जसु (चु. प. से.)
१७१९ जसु (चु. उ. से.)
१२१२ जसु (दि. प. से.)
१०७२ जागृ (अ. प. से.)
५६१ जि (भ्वा. प. से.)
९४६ जि (भ्वा. प. अ.)
१७९४ जि (चु. उ. अ.)
५९४ जिवि (भ्वा. प. अ.)
१२७९ जिरि (स्वा. प. अ.)
६९७ जिषु (भ्वा. प. अ.)
५६२ जीव (भ्वा. प. अ.)
१५७ जुगि (भ्वा. प. से.)
१३८० जुट (तु. प से.)
१३२७ जुड (तु. प. से.)
१६४७ जुड (चु. प. से.)
३२ जुतृ (भ्वा. आ. से.)
१३२७ जुन (पा.) (तु. प. से.)
१८३५ जुष (चु. उ. से.)
१२८९ जुषी (तु. आ. से.)
११५६ जूरी (दि. आ. से.)
६८१ जूष (भ्वा. प. से.)
३८९ जृभि (भ्वा. आ. से.)
१४९९ जॄ (क्रया. प. से.)
१८१५ जॄ (चु. उ. से.)
११३० जॄष् (दि. प. से.)
६४४ जेहृ (भ्वा. आ. से.)
६१६ जेषृ (भ्वा. आ. से.)
९१४ जै (भ्वा. प. अ.)
१६२५ ज्ञप (चु. प. से.)
८११ ज्ञा (भ्वा. प. अ.)

१५०८ ज्ञा	(क्र्या.	प.	अ.)
१७३३ ज्ञा	(चु.	उ.	अ.)
१५०० ज्या	(क्र्या.	प.	अ.)
९५६ ज्युङ्	(भ्वा.	आँ.	अ.)
९४७ ज्रि	(भ्वा.	आ.	से.)
१८१६ ज्रि	(चु.	उ.	से.)
७७६ ज्वर	(भ्वा.	प.	से.)
८०४ ज्वल	(भ्वा.	प.	से.)
८३१ ज्वल	(भ्वा.	प.	से.)
३०६ झट	(भ्वा.	प.	से.)
४७२ झमु	(भ्वा.	प.	से.)
१३०१ झर्झ	(तु.	प.	से.)
७१८ झर्झ	(भ्वा.	प.	से.)
६८९ झष	(भ्वा.	प.	से.)
८९१ झष	(भ्वा.	उ.	से.)
१४९५ झॄ (पा.)	(क्र्या.	प.	से.)
११३१ झॄष्	(दि.	प.	से.)
१६३९ टकि	(चु.	प.	से.)
८३४ टल	(भ्वा.	प.	से.)
१०३ टिकृ	(भ्वा.	आ.	से.)
१०४ टीकृ	(भ्वा.	आ.	से.)
८३५ ट्वल	(भ्वा.	प.	से.)
१६७७ डप	(चु.	आ.	से.)
१६७२ डिप	(चु.	आ.	से.)
१६७८ डिप	(चु.	आ.	से.)
१३७२ डिप	(तु.	प.	से.)
१२२३ डिप	(दि.	प.	से.)
९६८ डीङ्	(भ्वा.	आ.	से.)
११३५ डीङ्	(दि.	आ.	से.)
९८ ढौकृ	(भ्वा.	आ.	से.)
६६२ णक्ष	(भ्वा.	प.	से.)
१३४ णख	(भ्वा.	प.	से.)
१३५ णखि	(भ्वा.	प.	से.)
३१० णट	(भ्वा.	प.	से.)
७८१ णट	(भ्वा.	प.	से.)
५४ णद	(भ्वा.	प.	से.)
१७७९ णद	(चु.	उ.	से.)
१५२१ णभ	(क्र्या.	प.	से.)
७५२ णभ	(भ्वा.	आ.	से.)
१२४१ णभ	(दि.	प.	से.)
९८१ णम	(भ्वा.	प.	अ.)
४८० णय	(भ्वा.	आ.	से.)
८३८ णल	(भ्वा.	प.	से.)
११९५ णश	(दि.	प.	से.)
६२७ णस	(भ्वा.	आ.	से.)
११६७ णह	(दि.	उ.	अ.)
६२५ णासु	(भ्वा.	आ.	से.)
६५९ णिक्ष	(भ्वा.	प.	से.)
१०२६ णिजि	(अ.	आ.	से.)
१०९३ णिजिर्	(जु.	उ.	अ.)
६६ णिदि	(भ्वा.	प.	से.)
८७१ णिदृ	(भ्वा.	उ.	से.)
५९० णिवि	(भ्वा.	प.	से.)
१३६१ णिल	(तु.	प.	से.)
७२२ णिश	(भ्वा.	प.	से.)
१०२५ णिसि	(अ.	आ.	से.)
९०१ णीञ्	(भ्वा.	उ.	अ.)
५६६ णीव	(भ्वा.	प.	से.)
१०३५ णु	(अ.	प.	से.)
१२८३ णुद	(तु.	उ.	अ.)
१४२७ णुद	(तु.	प.	अ.)
१३९८ णू	(तु.	प.	से.)
८७२ णेदृ	(भ्वा.	उ.	से.)
६१७ णेषृ	(भ्वा.	उ.	से.)
११७ तक	(भ्वा.	प.	से.)
११८ तकि	(भ्वा.	प.	से.)
६६९ तक्ष	(भ्वा.	प.	से.)
६५५ तक्षू	(भ्वा.	प.	से.)
१४९ तगि	(भ्वा.	प.	से.)
३०८ तट	(भ्वा.	प.	से.)

१५८०	तड	(चु.	उ.	से.)
१८०२	तड	(चु.	उ.	से.)
२८०	तडि	(भ्वा.	आ.	से.)
१६७९	तत्रि	(चु.	आ.	से.)
१४६४	तनु	(त.	उ.	से.)
१८४१	तनु	(चु.	उ.	से.)
१९१	तन्चु	(भ्वा.	प.	से.)
१४६०	तन्चु	(रु.	प.	से.)
११५९	तप	(दि.	आ.	अ.)
९८५	तप	(भ्वा.	प.	अ.)
१८१९	तप	(चु.	उ.	से.)
१२०३	तमु	(दि.	प.	से.)
४७९	तय	(भ्वा.	आ.	से.)
१७८१	तर्क	(चु.	उ.	से.)
२२७	तर्ज	(भ्वा.	प.	से.)
१६८२	तर्ज	(चु.	आ.	से.)
५८	तर्द	(भ्वा.	प.	से.)
१५९९	तल	(चु.	उ.	से.)
१७३०	तसि	(चु.	उ.	से.)
१२१३	तसु	(दि.	प.	से.)
४८९	तायृ	(भ्वा.	आ.	से.)
१२६७	तिक	(स्वा.	प.	से.)
१०५	तिकृ	(भ्वा.	आ.	से.)
१२६८	तिग	(स्वा.	प.	से)
५७१	तिज	(भ्वा.	आ.	से.)
१६५३	तिज	(चु.	प.	से.)
३६२	तिपृ	(भ्वा.	आ.	अ.)
११२३	तिम	(दि.	प.	से.)
५३४	तिल	(भ्वा.	प.	से.)
१३५५	तिल	(तु.	प.	से.)
१६०८	तिल	(चु.	प.	से.)
५३४	तिल्ल (पा)	(भ्वा.	प.	से.)
१०६	तीकृ	(भ्वा.	आ.	से.)
१९१३	तीर	(चु.	उ.	से.)
१६६	तीव	(भ्वा.	प.	से.)
२४४	तुज	(भ्वा.	प.	से.)
१५६७	तुज. (पा.)	(चु.	प.	से.)
२४५	तुजि	(भ्वा.	प.	से.)
१५६७	तुजि	(चु	प.	से.)
१७५६	तुजि	(चु.	उ.	से.)
१३७७	तुट	(तु	प.	से.)
१३८७	तुड	(तु.	प.	से.)
२७६	तुडि	(भ्वा.	आ.	से.)
३९१	तुडृ	(भ्वा.	प.	से.)
१३३३	तुण	(तु.	प.	से.)
१९४४	तुत्थ	(चु.	उ.	से.)
१२८२	तुद	(तु.	उ.	अ.)
४०५	तुन्प	(भ्वा.	प.	से.)
१३११	तुन्प	(तु.	प.	से.)
४०९	तुन्फ	(भ्वा.	प.	से.)
१३१३	तुन्फ	(तु.	प.	से.)
४०४	तुप	(भ्वा.	प.	से.)
१३१०	तुप	(तु.	प.	से.)
४०८	तुफ	(भ्वा.	प.	से.)
१३१२	तुफ	(तु	प	से.)
१६९८	तुबि	(चु.	प.	से.)
४२८	तुबि	(भ्वा.	प.	से.)
७५३	तुभ	(भ्वा.	आ.	से.)
१५२२	तुभ	(क्र्या.	प.	से.)
१२४२	तुन	(दि.	प.	से.)
११०२	तुर	(जु.	प.	से.)
५७०	तुर्वी	(भ्वा.	प.	से.)
१६००	तुल	(चु.	प.	से.)
११८५	तुष	(दि.	प.	से.)
७१०	तुस	(भ्वा.	प.	से.)
७३७	तुहिर्	(भ्वा.	प.	से.)
३५१	तूडृ (पा.)	(भ्वा.	प.	से.)
१६९०	तूण	(चु.	आ.	से.)
११५२	तुरी	(दि.	आ.	से.)
६२७	तूल	(भ्वा.	प.	से.)

६७४ तूष	(भ्वा.	प.	से.)	
६६० तृक्ष	(भ्वा.	प.	से.)	
१४६९ तृणु	(त.	उ.	से.)	
१४४७ (उ) तृदिर्	(रु.	उ.	से.)	
१३०९ तृन्फ	(तु	प.	से.)	
११९६ तृप	(दि.	प.	से.)	
१२७२ तृप (पा)	(स्वा.	प.	से.)	
१८२० तृप	(चु.	उ.	से.)	
१३०८ तृप	(तु.	प.	से.)	
१३०८ तृफ (पा)	(तु.	प.	से.)	
१२२९ (ञि) तृष	(दि.	प.	से.)	
१४५६ तृह	(रु.	प.	से.)	
१३४९ तृहू	(तु.	प.	से.)	
१३५१ तृन्हु	(तु.	प.	से)	
९६९ तॄ	(भ्वा.	प.	से.)	
२३१ तेज	(भ्वा.	प.	से.)	
३६३ तेपृ	(भ्वा.	आ.	से.)	
४९९ तेवृ	(भ्वा.	आ.	से.)	
९८६ त्यज	(भ्वा.	प.	अ.)	
९७ त्रकि	(भ्वा.	आ.	से.)	
१५९ त्रख (पा)	(भ्वा.	प.	से.)	
६९ त्रदि	(भ्वा.	प.	से.)	
८१६ त्रपि (पा)	(भ्वा.	प.	से.)	
३७४ त्रपूष्	(भ्वा.	आ.	से.)	
१७४२ त्रस	(चु.	उ.	से.)	
१७६२ त्रसि	(चु.	उ.	से.)	
१११७ त्रसी	(दि.	प.	से.)	
१५९ त्रिखि (पा)	(भ्वा.	प.	से.)	
१३७६ त्रुट	(तु.	प.	से.)	
१६९९ त्रुट	(चु.	आ.	से.)	
४०७ त्रुन्प	(भ्वा.	प.	से.)	
४११ त्रुन्फ	(भ्वा.	प.	से.)	
४०६ त्रुप	(भ्वा.	प.	से.)	
४१० त्रुफ	(भ्वा.	प.	से.)	
९६५ त्रैङ्	(भ्वा.	आ.	अ.)	
९९ त्रौकृ	(भ्वा.	आ.	से.)	
६५६ त्वक्षू	(भ्वा.	प.	से.)	
१५० त्वगि	(भ्वा.	प.	से.)	
१३०२ त्वच	(तु.	प.	से.)	
१९२ त्वञ्चु	(भ्वा.	प.	से.)	
७७५ (ञि) त्वरा	(भ्वा.	आ.	से.)	
१००२ त्विष	(भ्वा.	उ.	से.)	
९५४ त्सर	(भ्वा.	प.	से.)	
१३८८ थुड	(तु.	प.	से.)	
५७१ थुर्वी	(भ्वा.	प.	से.)	
६०८ दक्ष	(भ्वा.	आ.	से.)	
७७० दक्ष	(भ्वा.	आ.	से.)	
१२७४ दघ	(स्वा.	प.	अ.)	
१९२७ दण्ड	(चु.	उ.	से.)	
१७ दद	(भ्वा.	आ.	से.)	
८ दध	(भ्वा.	आ.	से.)	
१२७१ दन्भु	(स्वा.	प.	से.)	
९८९ दन्श	(भ्वा.	प.	अ.)	
१२०४ दमु	(दि.	प.	से.)	
४८१ दय	(भ्वा.	आ.	से.)	
१०७३ दरिद्रा	(अ.	प.	से.)	
१७५२ दल	(चु.	उ.	से.)	
५४८ दल	(भ्वा.	प.	से.)	
८१६ दालि (पा)	(भ्वा.	प.	से.)	
१६७५ दाशि	(चु.	आ.	से.)	
१७६९ दाशि	(चु.	उ.	से.)	
१६७६ दस (पा)	(चु.	आ.	से.)	
१६७६ दासि	(चु.	आ.	से.)	
१७८७ दासि	(चु.	उ.	से.)	
१२१४ दसु	(दि.	प.	से.)	
९९१ दह	(भ्वा.	प.	अ.)	
१०९१ (डु) दाञ्	(जु.	उ.	अ.)	
९३० दाण्	(भ्वा.	प.	अ.)	
९९४ दान	(भ्वा.	उ.	से.)	
१०५९ दाप्	(अ.	प.	अ.)	

१२८०	दाश	(स्वा.	प.	से.)
८८२	दाशृ	(भ्वा.	उ.	से.)
८९४	दासृ	(भ्वा.	उ.	से.)
५९२	दिवि	(भ्वा.	प.	से.)
११०७	दिवु	(दि.	प.	से.)
१७०७	दिवु	(चु.	आ.	से.)
१७२५	दिवु	(चु.	उ.	से.)
१२८४	दिश	(तु.	उ.	अ.)
१०१५	दिह	(अ.	उ.	अ.)
६०९	दीक्ष	(भ्वा.	आ.	से.)
११३४	दीङ्	(दि.	आ.	अ.)
१०७६	दीधीङ्	(अ.	आ.	से.)
११५०	दीपी	(दि.	आ.	से.)
९४४	दु	(भ्वा.	प.	अ.)
१२५७	(टु) दु	(स्वा.	प.	अ.)
१९३१	दुःख	(चु.	उ.	से.)
१६०१	दुल	(चु.	प.	से.)
५७२	दुर्वी	(भ्वा.	प.	से.)
११८६	दुष	(दि.	प.	अ.)
१०१४	दुह	(अ.	उ.	अ.)
७३८	दुहिर्	(भ्वा.	प.	से.)
१२८१	दृ	(स्वा.	प.	से.)
११३३	दूङ्	(दि.	आ.	से.)
१४१२	दृङ्	(तु.	आ.	अ.)
१३१९	दृन्फ	(तु	प.	से.)
११९७	दृप	(दि.	प.	अ.)
१८२१	दृप (पा)	(चु.	उ.	से.)
१३१४	दृप	(तु.	प.	से.)
१८२३	दृभ	(चु.	उ.	से.)
१३२४	दृभी	(तु.	प.	से.)
१८२२	दृभी	(चु.	उ.	से.)
९८८	दृशिर्	(भ्वा.	प.	अ.)
७३३	दृह	(भ्वा.	प.	से.)
७३४	दृहि	(भ्वा.	प.	से.)
८०८	दॄ	(भ्वा.	प.	से.)
१४९४	दॄ	(क्र्या.	प.	से.)
७८	देकृ	(भ्वा.	आ.	से.)
९६२	देङ्	(भ्वा.	आ.	अ.)
५००	देवृ	(भ्वा.	आ.	से.)
९२४	दैप्	(भ्वा.	प.	अ.)
११४८	दो	(दि.	प.	अ.)
१०४०	द्यु	(अ.	प.	अ.)
७४१	द्युत	(भ्वा.	आ.	से.)
९०५	द्यै	(भ्वा.	प.	अ.)
४६६	द्रम	(भ्वा.	प.	से.)
१०५४	द्रा	(अ.	प.	अ.)
६७०	द्राक्षि	(भ्वा.	प.	से.)
१२४	द्राखृ	(भ्वा.	प.	से.)
११४	द्राघृ	(भ्वा.	आ.	से.)
२८७	द्राडृ	(भ्वा.	आ.	से.)
६४६	द्राहृ	(भ्वा.	आ.	से.)
९४५	द्रु	(भ्वा.	प.	अ.)
१३३८	द्रुण	(तु.	प.	से.)
११९८	द्रुह	(दि.	प.	से.)
१४८२	द्रूञ्	(क्र्या.	उ.	अ.)
९०६	द्रै	(भ्वा.	प.	अ.)
१०१३	द्विष	(अ.	उ.	अ.)
१५९९	धक्क	(चु.	प.	से.)
४५३	धण (पा)	(भ्वा.	प.	से.)
११०४	धन	(जु.	प.	से.)
५९७	धवि	(भ्वा.	प.	से.)
१०९२	(डु) धाञ्	(जु.	उ.	अ.)
६०१	धावु	(भ्वा.	उ.	से.)
१४०७	धि	(तु.	प.	अ.)
६०३	धिक्ष	(भ्वा.	आ.	से.)
५९३	धिवि	(भ्वा.	प.	से.)
११०३	धिष	(जु.	प.	से.)
११३६	धीङ्	(दि.	आ.	अ.)
६०२	धुक्ष	(भ्वा.	आ.	से.)
१२५६	धुञ्	(स्वा.	उ.	अ.)

५७३ धुर्वी	(भ्वा.	प.	से.)
१३९९ धू	(तु.	प.	से.)
१२५६ धूञ् (पा)	(स्वा.	उ.	से.)
१४८८ धूञ्	(क्र्या.	उ.	से.)
१८३६ धूञ्	(चु.	उ.	से.)
३९६ धूप	(भ्वा.	प.	से.)
१७७३ धूप	(चु.	प.	से.)
११५३ धूरी	(दि.	आ.	से.)
१६४० धूश (पा.)	(चु.	प.	से.)
१६४० धूष (पा.)	(चु.	प.	से.)
१६४० धूस	(चु.	प.	से.)
९३८ धृ	(भ्वा.	प.	से.)
९६० धृङ्	(भ्वा.	आ.	से.)
१४१२ धृङ्	(तु.	आ.	अ.)
२१९ धृज	(भ्वा.	प.	से.)
२२० धृजि	(भ्वा.	प.	से.)
९०० धृञ्	(भ्वा.	उ.	अ.)
१८५१ धृष	(चु.	उ.	से.)
१२७० (ञि) धृषा	(स्वा.	प.	से.)
१४९९ धॄ (पा)	(क्र्या.	प.	से.)
१९१९ धेक	(चु.	उ.	से.)
९०२ धेट्	(भ्वा.	प.	से.)
५५३ धोर्ऋ	(भ्वा.	प.	से.)
९२७ ध्मा	(भ्वा.	प.	अ.)
९०८ ध्यै	(भ्वा.	प.	अ.)
९४३ ध्र	(भ्वा.	प.	अ.)
२१७ ध्रज	(भ्वा.	प.	से.)
२१८ ध्रजि	(भ्वा.	प.	से.)
४५९ ध्रन	(भ्वा.	प.	से.)
१५२५ (उ) ध्रस	(क्र्या.	प.	से.)
१७४३ (उ) ध्रस	(चु.	प.	से.)
६७१ ध्राक्षि	(भ्वा.	प.	से.)
१२५ ध्राखृ	(भ्वा.	प.	से.)
२८८ ध्राडृ	(भ्वा.	आ.	से.)
११४ ध्राघृ (पा)	(भ्वा.	आ.	से.)
७९ ध्रेकृ	(भ्वा.	आ.	से.)
९०७ ध्रै	(भ्वा.	प.	अ.)
१४०१ ध्रु	(तु.	प.	अ.)
१४०१ ध्रुव (पा)	(तु.	प.	से.)
२२१ ध्वज	(भ्वा.	प.	से.)
२२२ ध्वजि	(भ्वा.	प.	से.)
४५३ ध्वण	(भ्वा.	प.	से.)
८१६ ध्वन	(भ्वा.	प.	से.)
८२८ ध्वन	(भ्वा,	प.	से.)
१८९० ध्वन	(चु.	उ.	से.)
८१६ ध्वनि (पा)	(भ्वा.	प.	से.)
७५५ ध्वन्सु	(भ्वा.	आ.	से.)
६७२ ध्वाक्षि	(भ्वा.	प.	से.)
९३९ ध्वृ	(भ्वा.	प.	अ.)
१५९४ नक्क	(चु.	प.	से.)
१५४६ नट	(चु.	प.	से.)
१७९२ नट	(चु.	उ.	से.)
६७ (टु) नदि	(भ्वा.	प.	से.)
५६ नर्द	(भ्वा.	प.	से.)
१८०३ नल	(चु.	उ.	से.)
६ नाथृ	(भ्वा.	आ.	से.)
७ नाधृ	(भ्वा.	आ.	से.)
१८८६ निवास	(चु.	उ.	से.)
६८७ निष्क	(चु.	आ.	से.)
५२२ नील	(भ्वा.	प.	से.)
१११६ नृती	(दि.	प.	से.)
८०९ नॄ	(भ्वा.	प.	से.)
१४९६ नॄ	(क्र्या.	प.	से.)
१५५१ पक्ष	(चु.	प.	से.)
२९६ पट	(भ्वा.	प.	से.)
१७५३ पट	(चु.	उ.	से.)
१८९७ पट	(चु.	उ.	से.)
३३० पठ	(भ्वा.	प.	से.)
२८१ पडि	(भ्वा.	आ.	से.)
१६१६ पडि	(चु.	प.	से.)

९९६	(डु) पचष्	(भ्वा.	उ.	अ.)
१७४	पचि	(भ्वा.	आ.	से.)
१६९२	पचि	(चु.	प.	से.)
१५७७	पछि	(चु.	प.	से.)
४३	पण	(भ्वा.	आ.	से.)
१८६२	पत	(चु.	उ.	से.)
८४५	पत्लृ	(भ्वा.	प.	से.)
१५५५	पथ (पा.)	(चु.	प.	से.)
१५७६	पथि	(चु.	प.	से.)
८४७	पथे	(भ्वा.	प.	से.)
११७०	पद	(दि.	आ.	अ.)
१८९९	पद	(चु.	आ.	से.)
४४०	पन	(भ्वा.	आ.	से.)
४७६	पय	(भ्वा.	आ.	से.)
१९४०	पर्ण	(चु.	उ.	से.)
२९	पर्द	(भ्वा.	आ.	से.)
४१२	पर्प	(भ्वा.	प.	से.)
४१६	पर्ब	(भ्वा.	प.	से.)
५७७	पर्व	(भ्वा.	प.	से.)
८३९	पल	(भ्वा.	प.	से.)
१८८२	पल्पूल	(चु.	उ.	से.)
१७२०	पश	(चु.	उ.	से.)
१८६३	पष	(चु.	उ.	से.)
१६१७	पसि	(चु.	प.	से.)
९२५	पा	(भ्वा.	प.	अ.)
१०५६	पा	(अ.	प.	अ.)
१९१२	पार	(चु.	उ.	से.)
१६१०	पाल	(चु.	प.	से.)
१४०६	पि	(तु.	प.	अ.)
१५७७	पिछ	(चु.	प.	से.)
१५६८	पिज (पा.)	(चु.	प.	से.)
१०२८	पिजि	(अ.	आ.	से.)
१५६८	पिजि	(चु.	प.	से.)
१७९८	पिजि	(चु.	उ.	से.)
३१३	पिट	(भ्वा.	प.	से.)

३३९	पिट	(भ्वा.	प.	से.)
२७४	पिडि	(भ्वा.	आ.	से.)
१६७०	पिडि	(चु.	प.	से.)
५८८	पिवि	(भ्वा.	प.	से.)
१४३८	पिश	(तु.	प.	से.)
१४५३	पिच्छ	(रु.	प.	से.)
१५६९	पिस	(चु.	प.	से.)
१७६३	पिसि	(चु.	उ.	से.)
७१९	पिसृ	(भ्वा.	प.	से.)
११४१	पीङ्	(दि.	आ.	अ.)
१५४५	पीड	(चु.	प.	से.)
५२१	पील	(भ्वा.	प.	से.)
५६३	पीव	(भ्वा.	प.	से.)
१३६८	पुट	(तु.	प.	स.)
१७५४	पुट	(चु.	उ.	से.)
१९१४	पुट	(चु.	उ.	से.)
१७९३	पुटि	(चु.	उ.	से.)
१५६०	पुट्ट	(चु.	प.	से.)
१३८९	पुड	(तु.	प.	से.)
३२६	पुडि (पा.)	(भ्वा.	प.	से.)
१३३४	पुण	(तु.	प.	से.)
१६३७	पुण (पा.)	(चु.	प.	से.)
११२९	पुथ	(दि.	प.	से.)
१७७६	पुथ	(चु.	उ.	से.)
४४	पुथि	(भ्वा.	प.	से.)
१३४७	पुर	(तु.	प.	से.)
५७६	पुर्व	(भ्वा.	प.	से.)
८४१	पुल	(भ्वा.	प.	से.)
१६०२	पुल	(चु.	प.	से.)
१६३७	पुल	(चु.	प.	से.)
७००	पुष	(भ्वा.	प.	से.)
११८३	पुष	(दि.	प.	अ.)
१५३०	पुष	(क्र्या.	प.	से.)
१७५१	पुष	(चु.	उ.	से.)
११२९	पुष्प	(दि.	प.	से.)

१६३८ पुंस	(चु.	प.	से.)
१५९१ पुस्त	(चु.	प.	से.)
९६६ पूङ्	(भ्वा.	आ.	से.)
१६४३ पूज	(चु.	प.	से.)
१४८३ पूञ्	(क्र्या.	उ.	से.)
४८४ पूयी	(भ्वा.	आ.	से.)
११५१ पूरी	(दि.	आ.	से.)
१८०४ पूरी	(चु.	उ.	से.)
१६३७ पूर्ण (पा)	(चु.	प.	से.)
५२८ पूल	(भ्वा.	प.	से.)
६७५ पूष	(भ्वा.	प.	से.)
१०८६ पृ (पा)	(जु.	प.	से.)
१२५९ पृ	(स्वा.	प.	अ.)
१४०३ पृङ्	(तु.	आ.	अ.)
१८०८ पृच	(चु.	उ.	से.)
१०३० पृची	(अ.	आ.	से.)
१४६२ पृची	(रु.	प.	से.)
१०१८ पृजि (पा.)	(अ.	आ.	से.)
१३२९ पृड	(तु.	प.	से.)
१३३० पृण	(तु.	प.	से.)
१५५५ पृथ	(चु.	प.	से.)
७०५ पृषु	(भ्वा.	प.	से.)
१०८६ पॄ	(जु.	प.	से.)
१४९० पॄ	(क्र्या.	प.	से.)
१५४९ पॄ	(चु.	प.	से.)
४४१ पेलृ	(भ्वा.	प.	से.)
५०४ पेवृ	(भ्वा.	आ.	से.)
६१५ पेषृ	(भ्वा.	आ.	से.)
७२० पेसृ	(भ्वा.	प.	से.)
९२० पै	(भ्वा.	प.	अ.)
४५८ पैणृ	(भ्वा.	प.	से.)
४८८ (ओ) प्यायी	(भ्वा.	आ.	से.)
९६४ प्यैङ्	(भ्वा.	आ.	से.)
१४१४ प्रच्छ	(तु.	प.	अ.)
७६५ प्रथ	(भ्वा.	आ.	से.)
१५५४ प्रथ	(चु.	प.	से.)
७६६ प्रस	(भ्वा.	आ.	से.)
१०६१ प्रा	(अ.	प.	अ.)
११४४ प्रीङ्	(दि.	आ.	अ.)
१४७५ प्रीञ्	(क्र्या.	उ.	अ.)
१८३७ प्रीञ्	(चु.	उ.	से.)
९५७ प्रुङ्	(भ्वा.	आ.	अ.)
३२४ प्रुड	(भ्वा.	प.	से.)
१५२८ प्रुष	(क्र्या.	प.	से.)
७०३ प्रुषु	(भ्वा.	प.	से.)
६१९ प्रेषृ	(भ्वा.	आ.	से.)
८६७ प्रोथृ	(भ्वा.	उ.	से.)
६४२ प्लिह	(भ्वा.	आ.	से.)
१५०४ प्ली	(क्र्या.	प.	अ.)
९५८ प्लुङ्	(भ्वा.	आ.	अ.)
११२५ प्लुष	(दि.	प.	से.)
१२१७ प्लुष	(दि.	प.	से.)
१५२९ प्लुष	(क्र्या.	प.	से.)
७०४ प्लुषु	(भ्वा.	प.	से.)
१०५५ प्सा	(अ.	प.	अ.)
११६ फक्क	(भ्वा.	प.	से.)
८२१ फण	(भ्वा.	प.	से.)
५३० फल	(भ्वा.	प.	से.)
५१६ (ञि) फला	(भ्वा.	प.	से.)
१३९१ फुल	(तु.	प.	से.)
५३२ फुल्ल	(भ्वा.	प.	से.)
५४२ फेलृ	(भ्वा.	प.	से.)
४५९ बण (पा.)	(भ्वा.	प.	से.)
५१ बद	(भ्वा.	प.	से.)
९७३ बध	(भ्वा.	आ.	से.)
१५४८ बध	(चु.	प.	से.)
१५४८ बन्ध (पा)	(चु.	प.	से.)
१५०९ बन्ध	(क्र्या.	प.	से.)
४१८ बर्ब	(भ्वा.	प.	से.)
६३८ बर्ह	(भ्वा.	आ.	से.)

१६६९ बर्ह	(चु.	प.	से.)
१७७० बर्ह	(चु.	उ.	से.)
८४० बल	(भ्वा.	प.	से.)
१३२९ बल	(चु	प.	से.)
६३९ बल्ह	(भ्वा.	आ.	से.)
१७७१ बल्ह	(चु.	उ.	से.)
२८६ बाडृ	(भ्वा.	आ,	से.)
९ बाधृ	(भ्वा.	आ.	से.)
६४९ बाहृ	(भ्वा.	आ.	से.)
३१६ बिट	(भ्वा.	प.	से.)
६४ बिदि	(भ्वा.	प.	से.)
१३६० बिल	(तु.	प.	से.)
१६०७ बिल	(चु.	प.	से.)
११९ बुक्क	(भ्वा.	प.	से.)
१७१४ बुक्क	(चु.	प.	से.)
८५८ बुध	(भ्वा.	प.	से.)
११७३ बुध	(दि.	आ.	अ.)
८७५ बुधिर्	(भ्वा.	उ.	से.)
१५९२ बुस्त	(चु.	व.	से.)
७३५ बृह	(भ्वा.	प.	से.)
७३६ बृहि	(भ्वा.	प.	से.)
१७६९ बृहि	(चु.	उ.	से.)
७३६ बृहिर् (पा.)	(भ्वा.	प.	से.)
१३४८ बृहू (पा)	(तु.	प.	से.)
१०४४ ब्रूञ्	(अ.	उ.	से.)
१६६४ ब्रूस	(चु.	प.	से.)
१५५८ भक्ष	(चु.	प.	से.)
९९८ भज	(भ्वा.	उ.	से.)
१७३४ भज	(चु.	उ.	से.)
१६६० भजि	(चु.	उ.	से.)
३०७ भट	(भ्वा.	प.	से.)
७८० भट	(भ्वा.	प.	से.)
२७३ भाडि	(भ्वा.	आ.	से.)
१५८९ भाडि	(चु.	प.	से.)
४४७ भण	(भ्वा.	प.	से.)

१२ भदि	(भ्वा.	आ.	से.)
१४५४ भञ्जो	(रु.	प.	से.)
१६८३ भर्त्स	(चु.	आ.	से.)
५८० भर्व	(भ्वा.	प.	से.)
४९५ भल	(भ्वा.	आ.	से.)
१७०१ भल	(चु.	आ.	से.)
४९६ भल्ल	(भ्वा.	आ.	से.)
६९५ भष	(भ्वा.	प.	से.)
११०० भस	(जु.	प.	से.)
१०५१ भा	(अ.	प.	अ.)
१८८७ भाज	(चु.	उ.	से.)
४४१ भाम	(भ्वा.	आ.	से.)
१८७३ भाम	(चु.	उ.	से.)
६१२ भाष	(भ्वा.	आ.	से.)
६२४ भासृ	(भ्वा.	आ.	से.)
६०६ भिक्ष	(भ्वा.	आ.	से.)
६४ भिदि (पा.)	(भ्वा.	प.	से.)
१४४० भिदिर्	(रु.	उ.	अ.)
१०८४ (ञि) भी	(जु.	प.	अ.)
१४५५ भुज	(रु.	प.	से.)
१४१८ भुजो	(तु.	प.	से.)
१७४८ भुव	(चु.	उ.	से.)
१ भू	(भ्वा.	प.	से.)
१८४५ भू	(चु.	उ.	से.)
६८२ भूष	(भ्वा.	प.	से.)
१७३१ भूष	(चु.	उ.	से.)
१७८ भृजी	(भ्वा.	आ.	से.)
८९८ भृञ्	(भ्वा.	उ.	अ.)
१०८७ (डु) भृञ्	(जु.	उ.	अ.)
१३९६ भृड	(तु.	प.	से.)
१७८८ भृशि	(चु.	उ.	से.)
१२२५ भृशु	(दि.	प.	से.)
१४९२ भॄ	(क्र्या.	प.	से.)
८८३ भेषृ	(भ्वा.	उ.	से.)
६२८ भ्यस	(भ्वा.	आ.	से.)

८९२	भ्रक्ष	(भ्वा.	उ.	से.)
४५२	भ्रण	(भ्वा.	प.	से.)
७५६	भ्रन्शु (पा.)	(भ्वा.	आ.	से.)
१२२६	भ्रन्शु	(दि.	प.	से.)
७५६	भ्रन्सु	(भ्वा.	आ.	से.)
८५०	भ्रमु	(भ्वा.	प.	से.)
१२०६	भ्रमु	(दि.	प.	से.)
१२८५	भ्रस्ज	(तु.	उ.	अ.)
१८१	भ्राजृ	(भ्वा.	आ.	से.)
८२३	(टु) भ्राजृ	(भ्वा.	आ.	से.)
८२४	(टु) भ्राशृ	(भ्वा.	आ.	से.)
१५०६	भ्री	(क्र्या.	प.	अ.)
१६९१	भ्रूण	(चु.	आ.	से.)
१८०	भ्रेजृ	(भ्वा.	आ.	से.)
८८४	भ्रेषृ	(भ्वा.	उ.	से.)
८९३	भ्लक्ष	(भ्वा.	उ.	से.)
८२५	(टु) भ्लाशृ	(भ्वा.	आ.	से.)
८८५	भ्लेषृ	(भ्वा.	आ.	से.)
८९	मकि	(भ्वा.	आ.	से.)
१३२	मख	(भ्वा.	प.	से.)
१३३	मखि	(भ्वा.	प.	से.)
१४८	मगि	(भ्वा.	प.	से.)
१११	मघि	(भ्वा.	आ.	से.)
१६०	मघि	(भ्वा.	प.	से.)
१७१	मच	(भ्वा.	आ.	से.)
१७३	मचि	(भ्वा.	आ.	से.)
३३२	मठ	(भ्वा.	प.	से.)
२६३	मठि	(भ्वा.	आ.	से.)
२७२	माडि	(भ्वा.	आ.	से.)
३२१	मडि	(भ्वा.	प.	से.)
१५८८	मडि	(चु.	प.	से.)
४४८	मण	(भ्वा.	प.	से.)
१६८०	मत्रि	(चु.	आ.	से.)
४६	मथि	(भ्वा.	प.	से.)
८४८	मथे	(भ्वा.	प.	से.)
१७०६	मद	(चु.	आ.	से.)
१३	मदि	(भ्वा.	आ.	से.)
८१५	मदी	(भ्वा.	प.	से.)
१२०९	मदी	(दि.	प.	से.)
११७७	मन	(दि.	आ.	अ.)
१४७२	मनु	(त.	आ.	से.)
४२	मन्थ	(भ्वा.	प.	से.)
१५१२	मन्थ	(क्र्या.	प.	से.)
५५८	मभ्र	(भ्वा.	प.	से.)
४७७	मय	(भ्वा.	आ.	से.)
१६५०	मर्च	(चु.	प.	से.)
४१९	मर्व	(भ्वा.	प.	से.)
५७८	मर्व	(भ्वा.	प.	से.)
४९३	मल	(भ्वा.	आ.	से.)
४९४	मल्ल	(भ्वा.	आ.	से.)
५९९	मव	(भ्वा.	प.	से.)
५०८	मव्य	(भ्वा.	प.	से.)
७२४	मश	(भ्वा.	प.	से.)
६९२	मष	(भ्वा.	प.	से.)
१२२२	मसी	(दि.	प.	से.)
१०२	मस्क	(भ्वा.	आ.	से.)
१४१६	(टु) मस्जो	(तु.	प.	अ.)
७३०	मह	(भ्वा.	प.	से.)
१८६८	मह	(चु.	उ.	से.)
६३४	माहि	(भ्वा.	आ.	से.)
१८००	महि	(चु.	उ.	से.)
१०६२	मा	(अ.	प.	अ.)
६६९	माक्षि	(भ्वा.	प.	से.)
१०८८	माङ्	(जु.	आ.	अ.)
११४२	माङ्	(दि.	आ.	अ.)
९७२	मान	(भ्वा.	आ.	से.)
१७१०	मान	(चु.	आ.	से.)
१८४४	मान	(चु.	उ.	से.)
१८४७	मार्ग	(चु.	उ.	से.)
१६४९	मार्ज	(चु.	प.	से.)

८९९ माहृ (भ्वा. उ. से.)
१२९८ मिछ (तु. प. से.)
१७०७ मिजि (चु. उ. से.)
१२५१ (डु) मिञ् (स्वा. उ. अ.)
८६८ मिथृ (पा.) (भ्वा. उ. से.)
७४३ (ञि) मिदा (भ्वा. आ. से.)
१२४४ (ञि) मिदा (दि. प. से.)
१५४२ मिदि (चु. प. से.)
८६८ मिदृ (भ्वा. उ. से.)
८६८ मिधृ (पा.) (भ्वा. उ. से.)
१३६९ मिल (तु. प. से.)
१४३० मिल (तु. उ. से.)
५८९ मिवि (भ्वा. प. से.)
७२३ मिश (भ्वा प. से.)
१९२२ मिश्र (चु. उ. से.)
१३५३ मिष (तु. प. से.)
६९९ मिषु (भ्वा. प. से.)
९९२ मिह (भ्वा. प. अ.)
१८२९ मी (चु. उ. से.)
११३७ मीङ् (दि. आ. अ.)
१४७७ मीञ् (क्र्या. उ. अ.)
४६८ मीमृ (भ्वा. प. से.)
५१७ मील (भ्वा. प. से.)
५६४ मीव (भ्वा. प. से.)
१७४४ मुच (चु. उ. से.)
१७२ मुचि (भ्वा. आ. से.)
१४३१ मुच्लृ (तु. उ. अ.)
२९० मुज (भ्वा. प. से)
२९१ मुजि (भ्वा. प. से.)
१३७९ मुट (तु. प. से.)
१६१९ मुट (चु. प. से.)
२६९ मुठि (भ्वा. आ. से.)
३२३ मुड (भ्वा. प. से.)
२७९ मुडि (भ्वा. आ. से.)
[illegible] मुडि (भ्वा. प. से.)

१३३५ मुण (तु. प. से.)
१६ मुद (भ्वा. आ. से.)
१७४१ मुद (चु. उ. से.)
१३४४ मुर (तु. प. से)
२१२ मुर्छा (भ्वा. प. से.)
५७५ मुर्वी (भ्वा. प. से.)
१५३१ मुष (क्र्या. प. से.)
१२२१ मुस (दि. प. से.)
१६३२ मुस्त (चु. प. से.)
११९९ मुह (दि. प. से.)
९६७ मूङ् (भ्वा. आ. से.)
१९१० मूत्र (चु. उ. से.)
५२९ मूल (भ्वा. प. से.)
१६०४ मूल (चु. प. से.)
६७६ मूष (भ्वा. प. से.)
६६४ मृक्ष (भ्वा. प. से.)
१९०१ मृग (चु. आ. से.)
१४०४ मृङ् (तु. आ. अ.)
१८४९ मृजू (चु. उ. से.)
१०६६ मृजू (अ. प. से.)
१३२८ मृड (तु. प. से.)
१५१७ मृड (क्र्या. प. से.)
१३३२ मृण (तु. प. से.)
१५१६ मृद (क्र्या. प. से.)
८७४ मृधु (भ्वा. उ. से.)
१४२६ मृश (तु. प. अ.)
११६४ मृष (दि. उ. से.)
१८५० मृष (चु. उ. से.)
७०७ मृषु (भ्वा. प. से.)
१४२३ मॄ (क्र्या. प. से.)
९६१ मेङ् (भ्वा. आ. से.)
८६९ मेथृ (पा.) (भ्वा. उ. से.)
८६९ मेदृ (भ्वा. उ. से.)
८७० मेधृ (भ्वा. उ. से.)
८६० मेथृ (पा.) (भ्वा. उ. से.)

३७१	मेपृ	(भ्वा.	आ.	से.)
५०५	मेवृ	(भ्वा.	आ.	से.)
९२९	म्ना	(भ्वा.	प.	अ.)
६६४	म्रक्ष (पा.)	(भ्वा.	प.	से.)
१६६२	म्रक्ष	(चु.	प.	से.)
७६७	म्रद	(भ्वा.	आ.	से.)
१९९	म्रुचु	(भ्वा.	प.	से.)
१९३	म्रुन्चु	(भ्वा.	प.	से.)
२९३	म्रेडृ	(भ्वा.	प.	से.)
१९६	म्लुचु	(भ्वा.	प.	से.)
१९४	म्लुन्चु	(भ्वा.	प.	से.)
२०५	म्लेच्छ	(भ्वा.	प.	से.)
१६६२	म्लेच्छ	(चु.	प.	से.)
२९२	म्लेटृ	(भ्वा.	प.	से.)
५०६	म्लेवृ	(भ्वा.	आ.	से.)
९०४	म्लै	(भ्वा.	प.	अ.)
१६९३	यक्ष	(चु	आ.	से.)
१००२	यज	(भ्वा.	उ.	अ.)
१७३६	यत	(चु.	उ.	से.)
३०	यती	(भ्वा.	आ.	से.)
१५३७	यत्रि	(चु.	प.	से.)
९८०	यम	(भ्वा.	प.	अ.)
९८४	यम	(भ्वा.	प.	अ.)
८१९	यमः	(भ्वा.	प.	से.)
१६२६	यम	(चु.	प.	से.)
१२११	यसु	(दि.	प.	से.)
१०४९	या	(अ.	प.	से.)
८६३	(टु) याचृ	(भ्वा.	उ.	से.)
१०३३	यु	(अ.	प.	से.)
१७११	यु	(चु.	आ.	से.)
१९६	युगि	(भ्वा.	प.	से.)
२१४	युछ	(भ्वा.	प.	से.)
११७८	युज	(दि.	आ.	अ.)
१८०७	युज	(चु.	उ.	से.)
१४५९	युजिर	(रु.	उ.	अ.)
१४८०	युञ्	(क्र्या.	उ.	अ.)
३१	युतृ	(भ्वा.	आ.	से.)
११७४	युध	(दि.	आ.	अ.)
१२२६	युपु	(दि.	प.	से.)
१२१६	युस (पा)	(दि.	प.	से.)
६८०	यूष	(भ्वा.	प.	से.)
२९१	यौटृ	(भ्वा.	प.	से.)
१७३७	रक	(चु.	उ.	से.)
६५८	रक्ष	(भ्वा.	प.	से.)
१३६	रख	(भ्वा.	प.	से.)
१३७	रखि	(भ्वा.	प.	से.)
१७३८	रग (पा)	(चु.	उ.	से.)
१४४	रगि	(भ्वा.	प.	से.)
७८९	रगे	(भ्वा.	प.	से.)
१७३८	रघ (पा)	(चु.	उ.	से.)
१०७	रघि	(भ्वा.	आ.	से.)
१७९६	रघि	(चु.	उ.	से.)
१८६९	रच	(चु.	उ.	से.)
२९७	रट	(भ्वा.	प.	से.)
३३४	रट	(भ्वा.	प.	से.)
३३४	रठ (पा)	(भ्वा.	प.	से.)
४४५	रण	(भ्वा.	प.	से.)
७९९	रण	(भ्वा.	प.	से.)
८१६	रणि (पा)	(भ्वा.	प.	से.)
५३	रद	(भ्वा.	प.	से.)
११९४	रध	(दि.	प.	से.)
९९९	रञ्ज	(भ्वा.	उ.	अ.)
११६८	रन्ज	(दि.	उ.	अ.)
४०१	रप	(भ्वा.	प.	अ.)
४१३	रफ	(भ्वा.	प.	से.)
४१४	रफि	(भ्वा.	प.	से.)
३७६	रबि	(भ्वा.	आ.	से.)
५९६	रवि	(भ्वा.	प.	से.)
९७४	रभ	(भ्वा.	आ.	से.)
३८९	रभि (पा.)	(भ्वा.	आ.	से.)

१७३८ लग	(चु. उ. से.)			२०७ लाछि	(भ्वा. प. से.)		
१४५ लगि	(भ्वा. प. से.)			२४० लाज	(भ्वा. प. से.)		
७८६ लगे	(भ्वा. प. से.)			२४१ लाजि	(भ्वा. प. से.)		
१०८ लघि	(भ्वा. आ. से.)			१९३७ लाभ	(चु. उ. से.)		
१७६१ लघि	(चु. उ. से.)			१३६६ लिख	(तु. प. से.)		
१७९७ लघि	(चु. उ. से.)			१५५ लिगि	(भ्वा. प. से.)		
२०६ लछ	(भ्वा. प. से.)			१७४० लिगि	(चु. उ. से.)		
२३८ लज	(भ्वा. प. से.)			१४३४ लिप	(तु. उ. अ.)		
१५४४ लज (पा.)	(चु. प. से.)			११८० लिश	(दि. शा. अ.)		
१९२१ लज	(चु. उ. से.)			१४२२ लिश	(तु. प. अ.)		
२३९ लजि	(भ्वा. प. से.)			१०१६ लिह	(अ. उ. अ.)		
१५५८ लजि (पा)	(चु. प. से.)			१८१२ ली	(चु. उ. अ.)		
१७८५ लजि	(चु. उ. से.)			१५०२ ली	(क्र्या. प. से.)		
१९२१ लजि (पा.)	(चु. उ. से.)			११३९ लीङ्	(दि. आ. अ.)		
१२९१ (ओ) लजी	(तु. आ. से.)			१५५८ लुजि (पा)	(चु. प. से.)		
२९८ लट	(भ्वा. प. से.)			१७९९ लुजि	(चु. उ. से.)		
३५९ लड	(भ्वा. प. से.)			३१४ लुट	(भ्वा. प. से.)		
१५४१ लड	(चु. प. से.)			७४८ लुट	(भ्वा. आ. से.)		
८१४ लडि	(भ्वा. प. से.)			१३८२ लुट	(तु प. से.)		
१८०१ लडि	(चु. उ. से.)			१७५५ लुट	(चु. तु. से.)		
१५४३ (ओ) लडि	(चु. प. से.)			३२८ लुटि	(भ्वा. प. से.)		
४०२ लप	(भ्वा. प. से.)			३३७ लुट	(भ्वा. प. से.)		
३७७ लबि	(भ्वा. आ. से.)			७४९ लुट	(भ्वा. आ. से.)		
३७९ लबि	(भ्वा. आ. से.)			१२२३ लुठ	(दि. प. से.)		
९७९ (डु) लभष्	(भ्वा. आ. अ.)			३२८ लुठि (पा.)	(भ्वा. प. से.)		
४१७ लर्ब	(भ्वा. प. से.)			३४३ लुठि	(भ्वा. प. से.)		
३५९ लल (पा.)	(भ्वा. प. से.)			३४६ लुठि	(भ्वा. प. से.)		
१६८८ लल	(चु. आ. से.)			३१४ लुड (पा)	(भ्वा. प. से.)		
८८८ लष	(भ्वा. उ. से.)			३२८ लुडि (पा.)	(भ्वा. प. से.)		
७१४ लस	(भ्वा. प. से.)			१५६४ लुण्ठ	(चु. प. से.)		
१७२९ लस	(चु. उ. से.)			५९ लुथि	(भ्वा. प. से.)		
१२९२ (ओ) लस्जी	(तु. आ. से.)			१८७ लुन्च	(भ्वा. प. से.)		
१०५८ ला	(अ. प. अ.)			१२३८ लुप	(दि. प. से.)		
१२२ लाखृ	(भ्वा. प. से.)			१४३२ लुप्लृ	(तु. उ. अ.)		
११३ लाघृ	(भ्वा. आ. से.)			४२७ लुबि	(भ्वा. प. से.)		

१६५७ लुबि	(चु.	प.	से.)	
१२३९ लुभ	(दि.	प.	से.)	
१३०६ लुभ	(तु.	प.	से.)	
१४८४ लूञ्	(क्र्या.	उ.	से.)	
६७७ लूष	(भ्वा	प.	से.)	
१६११ लूष	(चु.	प.	से.)	
३७३ लेपृ	(भ्वा.	आ.	से.)	
७६ लोकृ	(भ्वा.	आ.	से.)	
१७७७ लोकृ	(चु.	उ.	से.)	
१६४ लोचृ	(भ्वा.	आ.	से.)	
१७७८ लोचृ	(चु.	उ.	से.)	
३५७ लोडृ	(भ्वा.	प.	से.)	
२५८ लोष्ट	(भ्वा.	आ.	से.)	
६६३ वक्ष	(भ्वा.	प.	से.)	
८८ वकि	(भ्वा.	आ.	से.)	
९५ वकि	(भ्वा.	आ.	से.)	
१३० वख	(भ्वा.	प.	से.)	
१३१ वखि	(भ्वा.	प.	से.)	
१४७ वगि	(भ्वा.	प.	से.)	
११० वघि	(भ्वा.	आ.	से.)	
१०६३ वच	(अ.	प.	अ.)	
१८४३ वच	(चु.	उ.	से.)	
२५२ वज	(भ्वा.	प.	से.)	
१६१८ वज	(चु.	प.	से.)	
७७९ वट	(भ्वा.	प.	से.)	
१८५८ वट	(चु.	उ.	से.)	
१९२० वट	(चु.	उ.	से.)	
३०० वट	(भ्वा.	आ.	से.)	
१५८७ वटि	(चु.	प.	से.)	
१९२० वटि (पा.)	(चु.	उ.	से.)	
३३१ वठ	(भ्वा.	प.	से.)	
२६२ वठि	(भ्वा.	आ.	से.)	
२७१ वडि	(भ्वा.	आ.	से.)	
१५८७ वडि (पा.)	(चु.	प.	से.)	
५५६ वण	(भ्वा.	प.	से.)	
१००९ वद	(भ्वा.	प.	से.)	
१८४२ वद	(चु.	उ.	से.)	
११ वदि	(भ्वा.	आ.	से.)	
४६२ वन	(भ्वा.	प.	से.)	
४६३ वन	(भ्वा.	प.	से.)	
८०३ वन	(भ्वा.	प.	से.)	
८०३ वनु (पा.)	(भ्वा.	प.	से.)	
१४७१ वनु	(त.	आ.	से.)	
१८९ वन्चु	(भ्वा.	प.	से.)	
१७०४ वन्चु	(चु.	आ.	से.)	
१००३ (डु) वप्	(भ्वा.	उ.	से.)	
५५७ वभ्र	(भ्वा.	प.	से.)	
८४९ (टु) वम्	(भ्वा.	प.	से.)	
४७५ वय	(भ्वा.	आ.	से.)	
१८५३ वर	(चु.	उ.	से.)	
१६२ वर्च	(भ्वा.	आ.	से.)	
१५५२ वर्ण	(चु.	प.	से.)	
१९३९ वर्ण	(चु.	उ.	से.)	
१६५५ वर्ध	(चु.	प.	से.)	
६१३ वर्ष	(भ्वा.	आ.	से.)	
६४० वर्ह	(भ्वा.	आ.	से.)	
४९१ वल	(भ्वा.	प.	से.)	
८१६ वलि (पा.)	(भ्वा.	प.	से.)	
१५७२ वल्क	(चु.	प.	से.)	
१९१७ वल्क	(चु.	उ.	से.)	
१४३ वल्ग	(भ्वा.	प.	से.)	
३९१ वल्भ	(भ्वा.	आ.	से.)	
४९२ वल्ल	(भ्वा.	आ.	से.)	
६४१ वल्ह	(भ्वा.	आ.	से.)	
१०८० वश	(अ.	प.	से.)	
६९१ वष	(भ्वा.	प.	से.)	
१००५ वस	(भ्वा.	प्र.	अ.)	
१०२३ वस	(अ.	आ.	अ.)	
१७४५ वस	(चु.	उ.	से.)	
१९४३ वस	(चु.	उ.	अ.)	

१२१९ वसु	(दि.	प.	से.)	१९०४ वीर	(चु.	आ.	से.)
१०१ वस्क	(भ्वा.	आ.	से.)	१९८ वुगि	(भ्वा.	प.	से.)
१६८४ वस्त	(चु.	आ.	से.)	८७८ (उ) वुन्दिर	(भ्वा.	उ.	से.)
१००४ वह	(भ्वा.	उ.	अ.)	१२२० वुस	(दि.	प.	से.)
६३३ वहि	(भ्वा.	आ.	अ.)	९२ वृक	(भ्वा.	आ.	से.)
१०५० वा	(अ.	प.	अ.)	६०४ वृक्ष	(भ्वा.	आ.	से.)
६६८ वाक्षि	(भ्वा.	प.	से.)	१५१० वृङ्	(क्र्या.	आ.	से.)
२०८ वाछि	(भ्वा.	प.	से.)	१०२९ वृजि (पा)	(अ.	आ.	से.)
१८८३ वात	(चु.	उ.	से.)	१०२९ वृजी	(अ.	आ.	से.)
११६३ वाशृ	(दि.	आ.	से.)	१४६२ वृजी	(रु.	प.	से.)
१८८५ वास	(चु.	उ.	से.)	१८१३ वृजी	(चु.	उ.	से.)
१४२४ विच्छ	(तु.	प.	से.)	१२५५ वृञ्	(स्वा.	उ.	से.)
१७७४ विच्छ	(चु.	उ.	से.)	१८१४ वृञ्	(चु.	उ.	से.)
१४४३ विचिर्	(रु.	उ.	अ.)	१३३१ वृण	(तु.	प.	से.)
१०९४ विजिर्	(जु.	उ.	अ.)	७५८ वृतु	(भ्वा.	आ.	से.)
१२९० (ओ) विजी	(तु.	आ.	से.)	११६० वृतु	(दि.	आ.	से.)
१४६१ (ओ) विजी	(रु.	प.	से.)	१७८२ वृतु	(चु.	उ.	से.)
३१७ विट	(भ्वा.	प.	से.)	७५९ वृधु	(भ्वा.	आ.	से.)
३३ विथृ	(भ्वा.	आ.	से.)	१७८३ वृधु	(चु.	उ.	से.)
१०६४ विद	(अ.	प.	से.)	१२२७ वृश	(दि.	प.	से.)
११७२ विद	(दि.	आ.	अ.)	१७०५ वृष	(चु.	आ.	से.)
१४५१ विद	(रु.	आ.	अ.)	७०६ वृषु	(भ्वा.	प.	से.)
१७०९ विद	(चु.	आ.	से.)	१३४८ वृहू	(तु.	प.	से.)
१४३३ विद्लृ	(तु.	उ.	अ.)	१४९१ वॄ	(क्र्या.	प.	से.)
१३२६ विध	(तु.	प.	से.)	१४८७ वॄञ्	(क्र्या.	उ.	से.)
१३५९ विल	(तु.	प.	से.)	१००६ वेञ्	(भ्वा.	उ.	से.)
१६०६ विल	(चु.	प.	से.)	८७७ वेणृ	(भ्वा.	उ.	से.)
१४२५ विश	(तु.	प.	से.)	३४ वेथृ	(भ्वा.	आ.	से.)
१५२७ विष	(क्र्या.	प.	से.)	८७७ वेनृ (पा)	(भ्वा.	उ.	से.)
६९८ विषु	(भ्वा.	प.	से.)	३६७ (टु) वेपृ	(भ्वा.	आ.	से.)
१६८६ विष्क	(चु.	आ.	से.)	१८८१ वेल	(चु.	उ.	से.)
१९४१ विष्क	(चु.	उ.	से.)	५३५ वेलृ	(भ्वा.	प.	से.)
१०९५ विष्लृ	(जु.	उ.	अ.)	५४० वेल्ल	(भ्वा.	प.	से.)
१२१८ विस	(दि.	प.	से.)	१०७७ वेवीङ्	(अ.	आ.	से.)
१०४८ वी	(अ.	प.	अ.)	२५५ वेष्ट	(भ्वा.	आ.	से.)

१०३२ शीङ् (अ. आ. से.)
३८३ शीभृ (भ्वा. आ. से.)
५२३ शील (भ्वा. प. से.)
१८७९ शील (चु. उ. से.)
१८३ शुच (भ्वा. प. से.)
११६६ शुचिर् (दि. उ. से.)
५१३ शुच्य (भ्वा. प. से.)
३४१ शुठ (भ्वा. प. से.)
१६४५ शुठं (चु. प. से.)
३४४ शुठि (भ्वा. प. से.)
३४१ शुठि (पा.) (भ्वा. प. से.)
१६४६ शुठि (चु. प. से.)
११९२ शुध (दि. प. अ.)
१३३७ शुन (तु. प. से.)
७४ शुन्ध (भ्वा. प. से.)
१८३३ शुन्ध (चु. उ. से.)
४३३ शुन्भ (भ्वा. प. से.)
१३२२ शुन्भ (तु. प. से.)
४३२ शुभ (भ्वा. प. प.)
७५० शुभ (भ्वा. प. से.)
१३२२ शुभ (तु. प. से.)
१६१९ शुल्क (चु. प. से.)
१६१२ शुल्ब (चु. प. से.)
११८४ शुष (दि. प. अ.)
१९०३ शूर (चु. आ. से.)
११५७ शूरी (दि. आ. से.)
१६१३ शूर्प (चु. प. से.)
५२६ शूल (भ्वा. प. से.)
६७९ शूष (भ्वा. प. से.)
७६० शृधु (भ्वा. आ. से.)
८७३ शृधु (भ्वा. उ. से.)
१७३९ शृधु (चु. उ. से.)
१४८९ शॄ (क्र्या. प. से.)
५४३ शेल (भ्वा. प. से.)
५०१ शैवृ (पा.) (भ्वा. आ. से.)
९१८ शै (भ्वा. प. अ.)
११४५ शो (दि. प. अ.)
४९९ शोणृ (भ्वा. प. से.)
२९० शौटृ (भ्वा. प. से.)
४१ श्च्युतिर् (भ्वा. प. से.)
५१८ श्मील (भ्वा. प. से.)
९६३ श्यैङ् (भ्वा. आ. अ.)
८४ श्रकि (भ्वा. आ. से.)
१५१ श्रगि (भ्वा. प. से.)
७९८ श्रण (भ्वा. प. से.)
१५७९ श्रण (चु. प. से.)
७९९ श्रथ (भ्वा. प. से.)
१५४७ श्रथ (चु. प. से.)
१८२४ श्रथ (चु. उ. से.)
१८७१ श्रथ (चु. उ. से.)
३५ श्रथि (भ्वा. आ. से.)
१५११ श्रन्थ (क्र्या. प. से.)
१५१३ श्रन्थ (क्र्या. प. से.)
१८३८ श्रन्थ (चु. उ. से.)
३९३ श्रन्भु (भ्वा. आ. से.)
१६२४ श्रभ्र (चु. प. से.)
१२०५ श्रमु (दि. प. से.)
८१० श्रा (भ्वा. प. अ.)
१०५२ श्रा (अ. प. अ.)
८९७ श्रिञ् (भ्वा. उ. से.)
७०१ श्रिषु (भ्वा प. से.)
१४७६ श्रीञ् (क्र्या. उ. अ.)
९४२ श्रु. (भ्वा. प. अ.)
९१९ श्रै (भ्वा. प. अ.)
४५६ श्रोणृ (भ्वा. प. से.)
८५ श्लकि (भ्वा. आ. से.)
१५२ श्लगि (भ्वा. प. से.)
८०० श्लथ (भ्वा. प. से.)
१२७ श्लाखृ (भ्वा. प. से.)
११५ श्लाघृ (भ्वा. आ. से.)

११८७	श्लिष	(दि.	प.	अ.)
१५७५	श्लिष	(चु.	प.	अ.)
७०२	श्लिषु	(भ्वा.	प.	से.)
७७	श्लोकृ	(भ्वा.	आ.	से.)
४५७	श्लोणृ	(भ्वा.	आ.	से.)
९६	श्वकि	(भ्वा.	आ.	से.)
१६६	श्वच	(भ्वा.	आ.	से.)
१६७	श्वचि	(भ्वा.	आ.	से.)
१५६६	श्वठ	(चु.	प.	से.)
१८५६	श्वठ	(चु.	उ.	से.)
१५६६	श्वठि (पा.)	(चु.	प.	से.)
१६२४	श्वभ्र	(चु.	प.	से.)
१६२३	श्वर्त	(चु.	प.	से.)
५४९	श्वल	(भ्वा.	प.	से.)
१५७१	श्वल्क	(चु.	प.	से.)
५५०	श्वल्ल	(भ्वा.	प.	से.)
१०६९	श्वस	(अ.	प.	से.)
१०१०	(टुओ) श्वि	(भ्वा.	प.	से.)
७४२	श्विता	(भ्वा.	आ.	से.)
१०	श्विदि	(भ्वा.	आ.	से.)
७८९	षगे	(भ्वा.	प.	से.)
१२६९	षघ	(स्वा.	प.	से.)
१६३	षच	(भ्वा.	आ.	से.)
९९७	षच	(भ्वा.	उ.	से.)
३१३	षट	(भ्वा.	प.	से.)
४६४	षण	(भ्वा.	प.	से.)
१६३४	षट्ट	(चु.	प.	से.)
१४६९	षणु	(त.	उ.	से.)
१८३२	(आङः) षद	(चु.	उ.	से.)
८५४	षद्लृ	(भ्वा.	प.	अ.)
१४२८	षद्लृ	(तु.	प.	अ.)
९८७	षन्ज	(भ्वा.	आ.	अ.)
४००	षप	(भ्वा.	प.	से)
८२९	षम	(भ्वा.	प.	से.)
१५५६	षम्ब	(चु.	प.	से.)
२२९	षर्ज	(भ्वा.	प.	से.)
४२४	षर्ब	(भ्वा.	प.	से.)
५८६	षर्व	(भ्वा.	प.	से.)
५४७	षल	(भ्वा.	प.	से.)
२०२	षस्ज	(भ्वा.	प.	से.)
१०७८	षस	(अ.	प.	से.)
८५२	षह	(भ्वा.	आ.	से.)
११२८	षह	(दि.	प.	से.)
१८१०	षह	(चु.	उ.	से.)
१५७०	षान्त्व	(चु.	प.	से.)
१४३५	षिच	(तु.	उ.	से.)
१२४९	षिञ्	(स्वा.	उ.	अ.)
१४७८	षिञ्	(क्र्या.	उ.	अ.)
३०४	षिट	(भ्वा.	प.	से.)
४७	षिध	(भ्वा.	प.	से.)
११९३	षिधु	(दि.	प.	से.)
४८	षिधू	(भ्वा.	प.	से.)
४३१	षिन्भु (पा.)	(भ्वा.	प.	से.)
४३०	षिभु (पा.)	(भ्वा.	प.	से.)
१३६४	षिल	(तु.	प.	से.)
११०८	षिवु	(दि.	प.	से.)
९४१	षु	(भ्वा.	प.	से.)
१०४१	षु	(अ.	प.	अ.)
१५६३	षुट्ट	(चु.	प.	से.)
१३४१	षुर	(तु.	प.	से.)
११२९	षुह	(दि.	प.	से.)
१४०९	षू	(तु.	प.	से.)
१०३१	षूङ्	(अ.	आ.	से.)
११३२	षूङ्	(दि.	आ.	से.)
१२४८	षूञ्	(स्वा.	उ.	अ.)
२९	षूद	(भ्वा.	आ.	से.)
१७१८	षूद	(चु.	उ.	से.)
४३१	षृन्भु	(भ्वा.	प.	से.)
४३०	षृभु	(भ्वा.	प.	से.)
५४३	षेल (पा.)	(भ्वा.	प.	से.)

९०१ षेवृ	(भ्वा.	आ.	से.)
९१९ षै	(भ्वा.	प.	अ.)
११४७ षो	(दि.	प.	अ.)
७८२ ष्टक	(भ्वा.	प.	से.)
७९० ष्टगे	(भ्वा.	प.	से.)
४६१ ष्टन	(भ्वा.	प.	से.)
३८६ ष्टभि	(भ्वा.	आ.	से.)
८३० ष्टम	(भ्वा.	प.	से.)
१२६६ ष्टिघ	(स्वा.	आ.	से.)
३६४ ष्टिपृ	(भ्वा.	आ.	से.)
११२४ ष्टिम	(दि.	प.	से.)
११२५ ष्टीम	(दि.	प.	से.)
१७९ ष्टुच	(भ्वा.	आ.	से.)
१०४३ ष्टुञ्	(अ.	प.	अ.)
१६७३ ष्टुप	(चु.	प.	से.)
३९४ ष्टुभु	(भ्वा.	आ.	से.)
३६९ ष्टेपृ	(भ्वा.	आ.	से.)
९२२ ष्टै	(भ्वा.	प.	से.)
९११ ष्ट्यै	(भ्वा.	प.	अ.)
९२८ ष्ठा	(भ्वा.	प.	अ.)
५६० ष्ठिवु	(भ्वा.	प.	से.)
१११० ष्ठिवु	(दि.	प.	से.)
१११२ ष्णसु	(दि.	प.	से.)
१०५२ ष्णा	(अ.	प.	अ.)
१२०१ ष्णिह	(दि.	प.	से.)
१५७३ ष्णिह	(चु.	प.	से.)
१०३८ ष्णु	(अ.	प.	अ.)
११११ ष्णुसु	(दि.	प.	से.)
१२०० ष्णुह	(दि.	प.	से.)
९२३ ष्णै	(भ्वा.	प.	अ.)
९४८ ष्मिङ्	(भ्वा.	आ.	से.)
१५७४ ष्मिङ् (पा.)	(चु.	प.	से.)
९७६ ष्वन्ज	(भ्वा.	आ.	अ.)
१८ ष्वद	(भ्वा.	आ.	से.)
१८०६ ष्वद	(चु.	उ.	से.)
१०६८ (ञि) ष्वप्	(अ.	प.	अ.)
१०० ष्वष्क	(भ्वा.	आ.	से.)
७४४ (ञि) ष्विदा	(भ्वा.	आ.	से.)
९०८ (ञि) ष्विदा	(भ्वा.	प.	से.)
११८९ ष्विदा	(दि.	प.	से.)
१८९२ सङ्केत	(चु.	उ.	से.)
१९२३ सङ्ग्राम	(चु.	उ.	से.)
१९०७ सत्र	(चु.	आ.	से.)
१८८८ सभाज	(चु.	उ.	से.)
१३२२ समी (पा.)	(दि.	प	से.)
१०७९ सस्ति	(अ.	प.	से.)
१२६४ साध	(स्वा.	प.	अ.)
१८८० साम	(चु.	उ.	से.)
१९९७ साम्ब (पा.)	(चु.	प.	से.)
१८६९ सार	(चु.	उ.	से.)
१९३० सुख	(चु.	उ.	से.)
१८७४ सूच	(चु.	उ.	से.)
१९०९ सूत्र	(चु.	उ.	से.)
६६६ सूर्क्ष	(भ्वा.	प.	से.)
५०९ सूर्क्ष्य	(भ्वा.	प.	से.)
९३९ सृ	(भ्वा.	प.	अ.)
१०९९ सृ	(जु.	प.	अ.)
११७९ सृज	(दि.	आ.	अ.)
१४१९ सृज	(तु.	प.	से.)
९८३ सृप्लृ	(भ्वा.	प.	से.)
८१ सेकृ	(भ्वा.	आ.	से.)
९७९ स्कन्दिर्	(भ्वा.	प.	से.)
३८७ स्कभि	(भ्वा.	आ.	से.)
१४७९ स्कुञ्	(क्र्या.	उ.	अ.)
९ स्कुदि	(भ्वा.	आ.	से.)
७६८ स्खद	(भ्वा.	आ.	से.)
८२० स्खदिर्	(भ्वा.	प.	से.)
५४४ स्खल	(भ्वा.	प.	से.)
८१६ स्खलि (पा.)	(भ्वा.	प.	से.)
६६१ स्तृक्ष	(भ्वा.	प.	से.)

१२५२	स्तृञ्	(स्वा.	उ.	अ.)
१३५०	स्तृहू	(तु.	प.	से.)
१४८५	स्तृञ्	(क्र्या.	उ.	से.)
१८६०	स्तन	(चु.	उ.	से.)
१८९८	स्तेन	(चु.	उ.	से.)
९१०	स्त्यै	(भ्वा.	प.	अ.)
१९२४	स्तोम	(चु.	उ.	से.)
८३६	स्थल	(भ्वा.	प.	से.)
१३८९	स्थुड	(तु.	प.	से.)
१९०५	स्थूल	(चु.	आ.	से.)
३	स्पर्ध	(भ्वा.	आ.	से.)
१४	स्पदि	(भ्वा.	आ.	से.)
८८७	स्पश	(भ्वा.	उ.	से.)
१६८१	स्पश	(चु.	आ.	से.)
१२६०	स्पृ	(स्वा.	प.	अ.)
१४२३	स्पृश	(तु.	प.	अ.)
१८७२	स्पृह	(चु.	उ.	से.)
१३९०	स्फर (पा.)	(तु.	प.	से.)
४८७	स्फायी	(भ्वा.	आ.	से.)
१५७३	स्फिट (पा.)	(चु.	प.	से.)
१६३५	स्फिट्ट	(चु.	प.	अ.)
२६०	स्फुट	(भ्वा.	आ.	से.)
१३७४	स्फुट	(तु.	प.	से.)
१७२३	स्फुट	(चु.	उ.	से.)
३२९	स्फुटि (पा.)	(भ्वा.	प.	से.)
३२९	स्फुटिर्	(भ्वा.	प.	से.)
१३९२	स्फुड	(तु.	प.	से.)
१५३८	स्फुडि	(चु.	प.	से.)
१३९०	स्फुर	(तु.	प.	से.)
२१३	स्फुर्छा	(भ्वा.	प.	से.)
१३९०	स्फुल (पा.)	(तु.	प.	से.)
२२९	(टुओ)स्फूर्जा	(भ्वा.	प.	से.)
१५७४	स्मिट	(चु.	प.	से.)
५१९	स्मील	(भ्वा.	प.	से.)
८०७	स्मृ	(भ्वा.	प.	अ.)

९३३	स्मृ	(भ्वा.	प.	अ.)
१२६०	स्मृ (पा.)	(स्वा.	प.	अ.)
७६१	स्यन्दू	(भ्वा.	आ.	से.)
१६९४	स्यम	(चु.	आ.	से.)
८२६	स्यमु	(भ्वा.	प.	से.)
८३	स्रकि	(भ्वा.	आ.	से.)
७६७	स्रम्भु	(भ्वा.	आ.	से.)
७५४	स्रंसु	(भ्वा.	आ.	से.)
११०९	स्रिवु	(दि.	प.	से.)
९४०	स्रु	(भ्वा.	प.	अ.)
८२	स्रेकृ	(भ्वा.	आ.	से.)
८१७	स्वन	(भ्वा.	प.	से.)
८२७	स्वन	(भ्वा.	प.	से.)
१८६४	स्वर	(चु.	उ.	से.)
१९	स्वर्द	(भ्वा.	आ.	से.)
२८	स्वाद	(भ्वा.	आ.	से.)
१८०६	स्वाद (पा.)	(चु.	उ.	से.)
९३२	स्वृ	(भ्वा.	प.	अ.)
३१२	हट	(भ्वा.	प.	से.)
३३९	हट	(भ्वा.	प.	से.)
९७७	हद	(भ्वा.	आ.	अ.)
१०१२	हन	(अ.	प.	अ.)
४६७	हम्म	(भ्वा.	प.	से.)
९१२	हय	(भ्वा.	प.	से.)
९१४	हर्य	(भ्वा.	प.	से.)
८३७	हल	(भ्वा.	प.	से.)
७२१	हसे	(भ्वा.	प.	से.)
१०९०	(ओ) हाक्	(जु.	प.	अ.)
१०८९	(ओ) हाङ्	(जु.	आ.	अ.)
१२५८	हि	(स्वा.	प.	अ.)
८६१	हिक्क	(भ्वा.	उ.	से.)
३१७	हिट (पा)	(भ्वा.	प.	से.)
२६८	हिडि	(भ्वा.	आ.	से.)
१३६१	हिल	(तु.	प.	से.)
५९१	हिवि	(भ्वा.	प.	से.)

१६८६	हिक्क (वा)	(चु.	आ.	से.)
१४५७	हिसि	(रु.	प.	से.)
१८३०	हिसि	(चु.	उ.	से.)
१०८३	हु	(जु.	प.	अ.)
२६९	हुडि	(भ्वा.	आ.	से.)
२७७	हुडि	(भ्वा.	आ.	से.)
३५२	हुडृ	(भ्वा.	प.	से.)
२११	हुर्छा	(भ्वा.	प.	से.)
८४४	हुल	(भ्वा.	प.	से.)
३५३	हूडृ	(भ्वा.	प.	से.)
१०९७	हृ	(जु.	प.	अ.)
८९९	हृञ्	(भ्वा.	उ.	अ.)
१२३०	हृष	(दि.	प.	से.)
७०९	हृषु	(भ्वा.	प.	से.)
१५३३	हेट	(क्र्या.	प.	से.)
२६६	हेठ	(भ्वा.	आ.	से.)
७७८	हेड	(भ्वा.	प.	से.)
२८४	हेडृ	(भ्वा.	आ.	से.)
६३१	हेषृ	(भ्वा.	आ.	से.)
२८५	होडृ	(भ्वा.	आ.	से.)
३५४	होडृ	(भ्वा.	प.	से.)
१०८२	ह्नुङ्	(अ.	आ.	अ.)
८०६	ह्मल	(भ्वा.	प.	से.)
७८७	ह्रग	(भ्वा.	प.	से.)
७११	ह्रस	(भ्वा.	प.	से.)
२६	ह्राद	(भ्वा.	आ.	से.)
१०८९	ह्री	(जु.	प.	अ.)
२१०	ह्रीच्छ	(भ्वा.	प.	से.)
६२२	ह्रेषृ	(भ्वा.	आ.	से.)
७८८	ह्लगे	(भ्वा.	प.	से.)
१६५९	ह्लप	(चु.	प.	से.)
७१२	ह्लस	(भ्वा.	प.	से.)
२७	ह्लादी	(भ्वा.	आ.	से.)
८०५	ह्वल	(भ्वा.	प.	से.)
९३१	ह्वृ	(भ्वा.	प.	से.)
९३४	ह्वॄ	(भ्वा.	प.	अ.)
१००८	ह्वेञ्	(भ्वा.	उ.	से.)

(४) कौमुद्यन्तर्गतवार्तिकसूची.

(५) कौमुद्यन्तर्गतपरिभाषासूची ।

(६) उणादिपाठसूची।

(७) फिट्सूत्रपाठसूची ।

दक्षिणाप्राईझ कमिटीनें पसंतकेलेला ग्रंथ.

वृक्षवर्णन (आ. दुसरी) ग्रंथकर्त्याची तसबीर व चरित्रासह किं. १० आणे, ट. ख. अर्धा आणा.

पुस्तकें.	रु.	आ.	पै.
मुंबईचा दंगा (पृष्ठें ९६.) ...	०	२	०
कथाकल्पतरु (ग्रंथ सं.१४ स्त	२०	०	०
तुकारामाची गाथा	२	८	०
बगिच्याचें पुस्तक (सचित्र)	३	८	०
मराठी भाषेचा कोश	२	०	०
संस्कृत प्राकृत कोश... ...	०	१२	०
करणघेला (पु. १. २. ३.)प्र.	०	१	६
पूर्वेकडील तारा (स्टार इन दि ईस्ट)	०	९	०
मोचनगड (आ. दु.) ...	०	१२	०
विष्णुशास्त्री चिपळूणकरचें च०	१	०	०
श्रीशिवछत्रपति (पृ. ३१६)	१	८	०
सायुज्यसदननाटक	१	०	०
संस्कृत कविपंचक	१	४	०
भजनामृत (आ० दुसरी)	०	०	३
गुरुचरित्र (रेशमी)... ...	१	१२	०
रामविजय (गणपत) ...	४	०	०
विजयीजिगीषा नाटक (शी स्टूप्स टू कौंकर)	०	१०	०
ाणभीमदेव (खरारजपूत)	०	८	०
अर्थशास्त्र	१	०	०
राव्यांच्या बखरीवर टीका ...	०	४	०
जानकी परणीय नाटक (म० भाषांतरासह)	२	०	०
शांतिमताई (पृ० २०३) ...	१	८	०
गोल्डननाइट (मौजेची रात्र)	०	२	०
बृहत्स्तोत्र सरित्सागर ...	२	४	०
मूर्ख भाग्यवान् नसतो काय?	०	२	०
पाडव्याची भेट (आ. दुसरी)	०	४	०
सतारीचें पहिलें पु० (घारपुरेकृत)	१	४	०
भलि खोड मोडली	०	२	०
नानाफडनवीसाचें चरित्र ...	१	१२	०

पुस्तकें.	रु.	आ.	पै.
अनुरागपत्रिका पृ. ३२... ...	०	२	०
पाटाची कीं थाटाची	०	२	०
गुलबकावली	१	०	०
दासबोध (बुक साईझ) ...	१	०	०
सरस्वतींचं थोरवी	०	१	६
युनाइटेड्स्टेटसची लोकस्थिति (प्रवासवृत्त)	१	८	०
धोब्याचें पुस्तक	०	१	०
आर्यवैद्यक व पश्चिमात्य वैद्यक	०	४	०
पण लक्षांत कोण घेतो? ...	२	०	०
शाहाणा नेथन (तेलंगकृत)...	१	०	०
संसारसुख	२	०	०
जोतिर्विलास (पृ० २०८) ...	१	८	०
प्रेमदर्शन नाटक	०	१२	०
ठकाचीजबानी...	२	८	०
तंट्याभिल (धनुर्धारी) ...	०	२	६
सत्यनिरूपण (आ. चवथी).	०	५	०
श्रीविक्रमादित्य...	१	४	०
भोजन बंधु पानतंबाखु (आ.दु.)	०	३	०
सुलेखन विद्या (आ. दु.)...	०	१	०
कुटुंब सुधारणा (आ. दु.).	०	२	०
पत्रावळी व द्रोण (आ. दु.)	०	२	०
मुंबईचें वर्णन (नकाशासह)	२	८	०
निहाल कुवर (वघांची गोष्ट)	१	१२	०
स्थानिकराज्यव्य०(ना०तेलंगकृत)	१	०	०
बालविवाह (आ. दु.) ...	०	१	०
तंतुवाद्य दर्शिका	०	६	०
शुचिर्भूतपणा (आ. दु.)...	०	३	०
अबलासंजीवन...	१	०	०
अद्भुतरामायण (सटीक)...	३	०	०
धोम महाबळेश्वर (आ. दु.).	०	१२	०
पाकशास्त्र (पृ. ३२६) ...	१	४	[illegible]